The Department of Public Instruction, Bombay.

ATHARVAVEDASAMHITÂ

WITH THE

COMMENTARY OF SÂYAṆÂCHÂRYA.

EDITED BY

SHANKAR PÂṆḌURANG PAṆḌIT, M. A.

Registered for Copy-right under Act XXV of 1867.

Vol. III.

Bombay:

GOVERNMENT CENTRAL BOOK DEPÔT.

1898

All rights reserved.

Price 10 Rupees.

163 G

4° A. or. 2840 m/3

BIBLIOTHECA
REGIA
MONACENSIS

BOMBAY:
PRINTED AT JAVAJI DADAJI'S "NIRNAYA-SAGAR" PRESS.

163 G

अथर्ववेदसंहिता

सायणाचार्यविरचितेन भाष्येण सहिता.

भाग ३.

पण्डितोपाभिधेन पाण्डुरङ्गसूनुना शंकरेण

संशोधिता.

सा च

मुंबय्यां

जावजी दादाजी

इत्येतेषां "निर्णयसागराख्य" मुद्रणयन्त्रालये मुद्रिता.

गवर्नमेन्ट सेन्ट्रल बुक डिपो.

अस्य च ग्रन्थस्य स्वामित्वं (१८६७) सप्तषष्ट्युत्तराष्टादशशतस्य पञ्चविंशं स्वनियममनुसृत्य संगृहीतम्।

१८९८.

मूल्यं १० रुप्यकाः

Explanations of Abbreviations, Symbols &c, used in the first two and the following volumes.

1. Where in the Ms. of the Bhâshya, the omission, by mistake of the scribe of one or more letters, or words, is apparent, the omission is supplied within [ ] such rectangular brackets.

2. Where quotations from other books are made in the Bhâshya, abbreviations and figures to show the names and sections of books are introduced in brackets of the same kind.

3. The letters and figures on the top of the right hand pages are to be understood as follows:—

(A) The figure following अ shows the number of the Anuvâka (section of a Kâṇḍa).

(B) The figure following सू shows the number of the Sûkta from the beginning of the Kâṇḍa.

(C) The figure outside the brackets shows the number of the Sûkta from the beginning of Atharvaveda.

4. In Kâṇḍas VIII to XIV and Kâṇḍas XVII and XVIII most of the Sûktas are subdivided into Sections of ten Ṛiks each, the last section being made of a few Ṛiks more or less. The Bhâshya follows this subdivision strictly. In this edition the numbers of the subdivision are shown in smaller figures in addition to the numbering in accordance with the Sûktas.

श्रीगणाधिपतये नमः ॥ निर्विघ्नम् अस्तु ॥

यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् ।
निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

एकादशकाण्डे पञ्चानुवाकाः । प्रथमेनुवाके सप्त सूक्तानि । तत्र "अग्ने जायस्व" इत्यादिसूक्तचतुष्टयम् अर्थसूक्तम् । तेन ब्रह्मौदनसवे निरुप्तहविरभिमर्शनसंपातदातृवाचनदानानि कुर्यात् । तत्र "अग्ने जायस्व" [१] इति प्रथमया ब्रह्मौदनादिसवयज्ञेषु मथ्यमानम् अग्निम् अनुमन्त्रयेत । "कृणुत धूमम्" [२] इति द्वितीयया मथनसमये उत्पद्यमानधूमानुमन्त्रणं कुर्यात् । "अग्नेजनिष्ठाः" [३] इति तृतीयस्या[1]स्त्रिभिः पादैर्मथ्यमा[2]नं जाताग्निम् अनुमन्त्रयेत । "अस्यै रयिम्" इति चतुर्थेन पादेन पत्न्यै फलं काङ्क्षन् अग्निम् अनुमन्त्रयेत । "समिद्धः" [४] इति चतुर्थ्या काष्ठैः प्रज्वाल्यमानम् अग्निम् अनुमन्त्रयेत । "उत्तमं नाकम्" इति चतुर्थं पादं दातारं वाचयेत् । यद् आह कौशिकः । "अग्नीन् आधास्यमानः स[3]वान् वा दास्यन्[3] संवत्सरं[4] ब्राह्मौदनिकम् अग्निं दीपयति" इत्युपक्रम्य "अग्ने जायस्वेति मथ्यमानम् अनुमन्त्रयते । पत्नी मन्त्रं संनमयति यज"मा[5]नश्च । कृणुत धूमम् इति धूमम् अग्नेजनिष्ठा इति जातं समिद्धो "अग्निरिति समिध्यमानम्" इति [कौ० ८.१] ॥

ब्रह्मौदनसवयज्ञ एव देवपितृमनुष्यार्थं व्रीहिराशीन् त्रेधा विभक्तान् "त्रेधा भागः" [५] इति ऋचस्त्रिभिः पादैः कर्ता अनुमन्त्रयेत । "यो देवानाम्" इति चतुर्थपादेन पत्नीम् अनुमन्त्रयेत । "अग्ने सहस्वान्" [६] इति ऋचा दातारम् अनुमन्त्र्य देवभागं कुम्भ्यां निर्वपेत् । सूत्रितं हि ।

---

1 S′ तृतीयया for तृतीयस्याः. 2 S′ °मथ्यमान°. 3 S′ सवांदास्यन्. We with *Kaus′ika.* 4 S′ सांवत्सरं. We with *Kaus′ika.* 5 S′ यजमानंच.

"आदिष्टान् अंशान् अजानत्यै प्रयच्छति । तांस्त्रेधा भाग इति व्रीहिरा-
"शिषु निदधाति । तेषां यः पितॄणां तं श्राद्धं करोति । यो मनुष्याणां
"तं ब्राह्मणान् भोजयति । यो देवानां तम् अग्ने सहस्वान् इति दक्षिणं
"जान्वाच्यापराजितामुखः प्रह्वो वा मुष्टिभिः प्रसृताञ्जलिभिः कुम्भ्यां नि-
"र्वपति" इति [कौ० ८.२] ॥

तत्रैव कर्मणि "साकं सजातैः" [७] इति ऋचा निरुप्तान् व्रीहीन् उलूखले आवपेत् । सूत्रितं हि । "साकं सजातैरिति व्रीहीन् उलूखल आवपति" इति [कौ० ८.२] ॥ अत्र "साकम्" इत्यर्धर्चेन उलूखले व्रीहीन् आवपेत् । "उर्ध्वो नाकस्य" इत्यर्धर्चेन पच्यमानस्य ओदनस्योपरि [1]गर्तं कुर्याद् इति भाष्यकारः ॥

तत्रैव कर्मणि ब्राह्मौदनिकस्याग्नेः पश्चाद्भागे औक्षं[2] वा आनडुहं वा चर्म प्रस्तृणन्तं यजमानम् "इयं मही" [८] इति ऋचा वाचयेत् । "इयं महीति चर्मास्तृणाति प्राग्ग्रीवम् उत्तरलोम" इति [कौ० ८.१] सूत्रात् ॥

"एतौ ग्रावाणौ" [९] इति ऋचः[3] प्रथमपादेन उलूखलमुसलं चर्मणि स्थापयेत् । "निर्भिन्ध्यंशून्" इति पादत्रयेण व्रीहीन् अवहन्यात् । "गृहाण ग्रावाणौ" इत्यर्धर्चेन उलूखलमुसलम् अवहननार्थं[4] पत्नीं ग्राहयेत् । "त्रयो वराः" इत्यर्धर्चेन निर्वापानन्तरं वरं [[5]वृणन्तावनुमन्त्रयते । सूत्रितं हि । "एतौ[5]] ग्रावाणौ [९] अयं ग्रावा [१२.३.१४] इत्युलूखलमुसलं [6]शूर्पं प्रक्षालितं चर्मण्याधाय गृहाण ग्रावाणौ [१०] इत्युभयं गृह्णाति" इति [कौ० ८.२] "निर्भिन्ध्यंशून् ग्राहिं पाप्मानम् इत्यवहन्ति" इति [कौ० ८.२] "त्रयो वरा इति त्रीन् वरान् वृणीष्व" इति च [कौ० ८.२] ॥

तत्र प्रथमा ॥

अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।
सप्तऋषयो[१] भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥ १ ॥

---

१ $\overset{h}{B}$ C K सप्तर्षयो. We with A D K R $\overset{m}{S}$ $\overset{m}{K}$ V Cs.

---

1 S′ मर्त. The emendation is conjectural. 2 S′ मौंजं. 3 S′ ऋचा. 4 S′ एव for अव°. 5 S′ has simply वृणीतौ in place of the words in the brackets. 6 S′ शूर्प°.

अग्ने। जायस्व। अदितिः। नाथिता। इयम्। ब्रह्मऽओदनम्। पचति। पुत्रऽकामा।
सप्तऽऋषयः। भूतऽकृतः। ते। त्वा। मन्थन्तु। प्रऽजया। सह। इह॥ १॥

हे अग्ने जायस्व मथनाद् उत्पद्यस्व। ⌛जनी प्रादुर्भावे। दिवादित्वात् श्यन्। "ज्ञाजनोर्जा" इति जादेशः⌛। किमर्थं जननप्रार्थनम् इति आह। नाथिता नाथमाना याचमाना। ⌛नाथृ याच्ञायाम्। अस्मात् कर्तरि निष्ठा⌛। इष्टफलम् आशंसमाना इयम् अदितिः अदीना देवमाता पुत्रकामा पुत्रान् कामयमाना। ⌛"शीलि[1]कमि[2]भक्षाचरिभ्यो णः" इति कर्मण्यण्प्रत्ययः⌛। ब्रह्मौदनम्। ब्रह्मणे जगत्स्रष्ट्रे स्वाहाकारेण देय ओदनो ब्रह्मौ[3]दनः। यद्वा ब्रह्मौदनसवाख्ये अस्मिन् कर्मणि ब्राह्मणानां भोजनाय भागत्वेन कल्पित ओदनो ब्रह्मौदनः। तं पचति निर्वापादिक्रमेण पक्वं करोति। तदर्थम् हे अग्ने जायस्वेत्यर्थः। ब्रह्मौदनपाकेन अदितेः पुत्रोत्पत्तिस्तैत्तिरीयके समाम्नायते। "अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत्। तस्या उच्छेषणम् अददुः। तत् [प्राश्नात्]। सा रेतोधत्त। तस्यै चत्वार आदित्या अजायन्त" इति [तै॰ सं॰ ६. ५. ६. १]। अदितिकर्तृकस्य ब्रह्मौदनपाकस्य पूर्वम् अतिवृत्तत्वेन इदानीम् अभावात् अदितिशब्दस्य स्थाने पत्नीयजमानयोर्नामग्रहणं कर्तव्यम्। यद् आह कौशिकः। "पत्नी मन्त्रं संनमयति यजमानश्च" इति [कौ॰ ८. २]। सप्तऋषयः सप्तसंख्याका ऋषयः अतीन्द्रियार्थस्य द्रष्टारो मरीच्यत्रिप्रमुखाः। ⌛"दिक्संख्ये संज्ञायाम्" इति संख्याशब्दस्य समानाधिकरणेन उत्तरपदेन समासः⌛। भूतकृतः भूतानां पृथिव्यादीनां कर्तारः स्रष्टारस्ते प्रसिद्धाः हे अग्ने त्वा त्वाम् इह अस्मिन् देवयजने प्रजया पुत्रपौत्रादिरूपया यजमानसंबन्धिन्या सह मन्थ[4]न्तु मथनेन उत्पादयन्तु। ⌛मन्थ विलोडने इति धातुः⌛॥

---

१ P कृतऽकृतः. We with P[2] J Cp.

---

1 S′ शीलिका°. 2 S′ °भिक्षा°. 3 S′ ब्रह्मो°. 4 S′ मंथतु.

द्वितीया ॥

कृणुत धूमं वृषणः सखायोद्रोघाविता वाचमच्छ ।
अयमग्निः पृतनाषाट् सुवीरो येन देवा असहन्त दस्यून् ॥ २ ॥

कृणुत । धूमम् । वृषणः । सखायः । अद्रोघऽअविताः । वाचम् । अच्छ ।
अयम् । अग्निः । पृतनाषाट् । सुऽवीरः । येन । देवाः । असहन्त । दस्यून् ॥२॥

हे वृषणः वृषाणः कामानां वर्षितारः । "वा षपूर्वस्य निगमे" इति दीर्घाभावः । सखायः समानख्यानाः सर्वजगन्मित्रभूताः सप्तऋषयः ऋत्विजो वा यूयं धूमं कृणुत मथनेन उत्पादयत । कृवि हिंसाकरणयोश्च । "धिन्विकृण्व्योर च" इति उप्रत्ययः । "सतिशिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्यः" इति वचनात् तिङ एव उदात्तत्वम् । पादादित्वात् निघाताभावः ॥ अद्रोघाविता अद्रोहकारिणां सुचरित्राणां[1] यजमानानाम् अविता रक्षिता वाचम् अच्छ मथ्यमानाग्नेः स्तुत्यर्थम् अनूच्यमानाम् ऋग्रूपां वाचम् अभिलक्ष्य अयं जायमानोग्निः पृतनाषाट् पृतनाः शात्रवीः सेनाः सहते अभिभवतीति पृतनाषाट् । षह अभिभवे । "छन्दसि सहः" इति ण्विप्रत्ययः । "सहेः साडः सः" इति षत्वम् । "अग्ने हंसि न्यत्त्रिणम्" इति निगमः [ऋ० सं० १०. ११८. १] । सुवीरः वीरा विक्रान्ता देवाः शोभनैस्तैरुपेतः । यद्वा वीर्याज्जायन्त इति वीराः पुत्रा यजमानसंबन्धिनः । शोभनैस्तैर्युक्तः । जायत इत्यर्थः । "वीरवीर्यौ च" इति उत्तरपदाद्युदात्तत्वम् । शोभनवीर्योपेतत्वम् अग्नेः समर्थयते । येन अग्निना देवा इन्द्रादयो दस्यून् उपक्षपयितॄन् असुरान् असहन्त अभ्यभवन् । सोयम् अग्निरिति संबन्धः ॥

---

१ All our MSS. and vaidikas असहन्त (the pada MSS. and vaidikas असहन्त) except **C**s, which has असहन्त changed to असहन्त, and this I adopt, though I suspect the authority of **C**s for the correction is the accent in the corresponding passage in the *Rigveda* (III. 29. 9). २ **P**[2] **J** °अविताः. **C**P °अविता corrected to °अविताः. We with **P**.

---

1 **S′** सचरि°.

तृतीया ॥

अग्नेर्जनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।
सप्तऋषयो भूतकृतस्ते त्वाजीजनन्नस्यै रयिं सर्ववीरं नि यच्छ ॥ ३ ॥

अग्ने । अर्जनिष्ठाः । महते । वीर्याय । ब्रह्मऽओदनाय । पक्तवे । जातऽवेदः । सप्तऽऋषयः । भूतऽकृतः । ते । त्वा । अजीजनन् । अस्यै । रयिम् । सर्वऽवीरम् । नि । यच्छ ॥ ३ ॥

हे अग्ने अजनिष्ठाः मथनेन उत्पन्नो भवसि । जनी प्रादुर्भावे । लुङि रूपम् । महते प्रभूताय वीर्याय सामर्थ्याय । लोके दाहपाकक्षमस्याग्नेः सद्भावेपि मन्त्रसामर्थ्येन मयि तस्माद् अग्नेरेव वीर्याधिक्यं जायत इत्यर्थः । यस्माद् एवम् अग्नेर्वीर्यं महत् तस्माद् विशिनष्टि । हे जातवेदः जातानाम् उत्पन्नानां प्राणिनां वेदितरग्ने ब्रह्मौदनाय पक्तवे । पचेस्तुमर्थे तवेन् प्रत्ययः । [पक्तुं] भूतकृतः भूतानां पृथिव्यादीनां कर्तारः स्रष्टारस्ते प्रसिद्धाः सप्तऋषयः त्वा त्वाम् अजीजनन् मन्त्रसामर्थ्येन निरतिशयवीर्यम् उदपीपदन् । जनेर्ण्यन्तात् लुङि चङि रूपम् । अस्यै पत्न्यै सर्ववीरम् सर्वैर्वीरैः पुत्रपौत्रादिरूपैर्युक्तं रयिम् धनं नि यच्छ नियमय । यथा एनां रयिः प्राप्नोति तथा कुर्वित्यर्थः । यम उपरमे । "इषुगमियमां छः" इति छत्वम् । अथ वा नितरां प्रयच्छ । दाण् दाने । "पाघ्रा°" इत्यादिना यच्छादेशः ॥

चतुर्थी ॥

समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियाँ एह वक्षः ।
तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥ ४ ॥

समऽइद्धः । अग्ने । समऽइधा । सम् । इध्यस्व । विद्वान् । देवान् । यज्ञियान् । आ । इह । वक्षः ।

१ B[h] C K सप्तर्षयो. We with A B D K[m] R S[m] V Cs. २ P इधस्व. We with P[2] J Cp.

1 S′ जातवेदः after पक्तवे.

तेभ्यः । हविः । श्रपयन् । जातऽवेदः । उतऽतमम् । नाकम् । अधि । रोहय । इमम् ॥ ४ ॥

हे अग्ने समिद्धः संदीप्तस्त्वं समिधा मन्त्रेण आधीयमानया पलाशादिवृक्षसंभूतया समिद्धः[*1] पुनरलौकिकप्रभावेन संदीपितः सः[*1] तादृशस्त्वं विद्वान् जानन् यज्ञियान् यज्ञार्हान् देवान् । ⧗ "यज्ञर्त्विग्भ्यां घखञौ" इति घप्रत्ययः ⧗ । इह अस्मिन् देवयजने यजमाने वा आ वक्षः आवह । ⧗ वहेर्लेटि अडागमः । "सिब्बहुलं लेटि" इति सिप् । ढत्वकत्वषत्वानि ⧗ । हे जातवेदः जातानां वेदितरग्ने तेभ्यो देवेभ्यः हविः श्रपयन् ब्रह्मौदनलक्षणम् अन्नं पचन् । ⧗ श्रा पाके इत्यस्मात् ण्यन्तात् लटः शत्रादेशः । आकारान्तलक्षणे पुकि कृते घटादिपाठात् "मितां ह्रस्वः" इति उपधाह्रस्वत्वम् ⧗ । इमं यजमानम् उत्तमम् अतिशयेन उत्कृष्टं नाकम् दुःखसंस्पर्शरहितं स्वर्गं लोकम् अधि रोहय । देहावसानानन्तरं प्रापयेत्यर्थः । ⧗ उत्तमम् इति । "उत्तमशश्वत्तमौ सर्वत्र" इति उञ्छादिषु पाठात् अन्तोदात्तत्वम् । नाकम् इति । नास्मिन् अकम् अस्तीति नाकः । "नभ्राण्नपात्°" इत्यादिना नञः प्रकृतिभावः ⧗ ॥

पञ्चमी ॥

त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।
अंशान्[2] जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥ ५ ॥

त्रेधा । भागः । निऽहितः । यः । पुरा । वः । देवानाम् । पितॄणाम् । मर्त्यानाम् ।
अंशान् । जानीध्वम् । वि । भजामि । तान् । वः । यः । देवानाम् । सः । इमाम् । पारयाति ॥ ५ ॥

---

१ P[2] श्रपयम्. We with P J Cp. २ A B[h] D K[m] Cs अंशांजानी°. We with C R S[m] V.

1 S′ Sâyaṇa's text too is समिद्धः स for समिध्यस्व. The latter is a better reading than Sâyaṇa's.

वः युष्माकं देवानाम् अग्न्यादीनां पितॄणाम् पितृपितामहप्रपितामहानां मर्त्यानाम् मनुष्याणां [1]भोजयितव्यानां ब्राह्मणानां यो भागस्त्रेधा त्रिविधः [पुरा] निहितः व्रीह्यवस्थायां विभज्य स्थापितः । ⧖ "एधाच्च" इति त्रिशब्दाद् विधार्थे एधाच् प्रत्ययः ⧖ । हे देवाद्याः अंशान् भागान् जानीध्वम् अवगच्छत । ⧖ ज्ञा अवबोधने । क्र्यादित्वात् श्ना प्रत्ययः । "ज्ञाजनोर्जा" इति जादेशः ⧖ । वः युष्मभ्यं तान् भागान् अहं वि भजामि पृथक्करोमि । तत्र देवार्थेन भागेन निर्वापादिकं कर्तव्यम् पित्रर्थेन वृद्धिश्राद्धम् मनुष्यार्थेन ब्राह्मणभोजनम् इति विभागस्य उपयोगः । तत्र देवानां यो भागः सः अग्नौ हवीरूपेण हूयमानः सन् इमां पत्नीं पारयाति इष्टफलस्य पारं गमयति । ⧖ पार तीर कर्मसमाप्ताविति धातुः ⧖ ॥

षष्ठी ॥

अग्ने सहस्वानभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥ ६ ॥

अग्ने । सहस्वान् । अभिऽभूः । अभि । इत् । असि । नीचः । नि । उब्ज । द्विषतः । सऽपत्नान् ।
इयम् । मात्रा । मीयमाना । मिता । च । सऽजातान् । ते । बलिऽहृतः । कृणोतु ॥ ६ ॥

हे अग्ने सहस्वान् सहः पराभिभवनक्षमं बलं तद्वान् । ⧖ "तसौ मत्वर्थे" इति भत्वात् पदत्वाभावाद् रुत्वाभावः ⧖ । अत एव अभिभूः अभिभविता शत्रूणाम् अभ्यसि । इत् अवधारणे । अभिभवस्येव । सर्वोत्कृष्टो वर्तस इत्यर्थः । तस्माद्धेतोः [द्विषतः] द्वेष्टॄन् अप्रियकारिणः सपत्नान् अस्मदीयान् शत्रून् नीचः न्यञ्चनान् नीचीनगमनान् क्षयिष्णून् न्युब्ज अधोमुखान् पातय । ⧖ निपूर्वाद् अञ्चतेः "ऋत्विग्०" इत्यादिना क्विन् । "अनिदिताम्०" इति नलोपः । शसि भसंज्ञायाम् "अचः" इत्यकारलोपे "चौ" इति दीर्घत्वम् । न्युब्जेति । उब्ज आ-

1 S' भांजयितव्यानाम्.

जेवे । अत्र उपसर्गवशाद् अधोमुखीकरणम् अर्थः । यथा "दशाभिः कलशौ[1] मृष्ट्वा न्युब्जति" इति [आप० १२.२९.९] । मात्रा निर्मात्रा मीयमाना क्रियमाणा मिता निर्मिता च इयं शाला हे यजमान ते तुभ्यं सजातान् समानजन्मनः पुरुषान् बलिहृतः । बलिः उपायनद्रव्यम् । तस्य हर्तॄन् कृणोतु करोतु ॥

सप्तमी ॥

साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।
ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥ ७ ॥

साकम् । सऽजातैः । पयसा । सह । एधि । उत् । उब्ज । एनाम् । महते । वीर्याय ।
ऊर्ध्वः । नाकस्य । अधि । रोह । विष्टपम् । स्वःऽगः । लोकः । इति । यम् । वदन्ति ॥ ७ ॥

हे यजमान सजातैः समानजन्मभिः पुरुषैः साकम् सार्धं पयसा पयोवत्सारभूतेन कर्मफलेन सह एधि भव । अस्तेर्लोटि "सेर्ह्यपिच्च" इति हिरादेशः । "ध्वसोरेद्धावभ्यासलोपश्च" इति एत्वम् । तस्य "असिद्धवद् अत्रा भात्" इति असिद्धत्वात् "हुझल्भ्यो हेर्धिः" इति धित्वं भवति । एनां पत्नीं महते अधिकाय वीर्याय यथा एषा महद् वीर्यं प्राप्नोति तथा उद् उब्ज उद्गमय उन्नतशिरस्कां कुरु । हे यजमान त्वं देहावसाने ऊर्ध्वः ऊर्ध्वदिगभिमुखः सन् नाकस्य दुःखसंस्पर्शरहितस्य लोकस्य विष्टपम् उपरिप्रदेशम् अधि रोह अधिरूढो भव । यं स्थानविशेषं स्वर्गो लोकः लोकनीयः सुकृतफलोपभोगप्रदेश इति वदन्ति अभिज्ञाः कथयन्ति ॥

अष्टमी ॥

इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
अथ गच्छेम सुकृतस्य लोकम् ॥ ८ ॥

---

1 S' कलशो for कलशौ.

इयम् । मही । प्रति । गृह्णातु । चर्म । पृथिवी । देवी । सुऽमनस्यमाना ।
अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥ ८ ॥

इयं पुरोवर्तिनी मही देवयजनभूमिः चर्म आनडुहं निर्वापार्थम् आस्तीर्यमाणम् अजिनं प्रति गृह्णातु स्वीकरोतु । आस्तीर्णाजिना सा पृथिवी देवी देवतारूपा सुमनस्यमाना शोभनं मनः कुर्वती अनुग्रहबुद्धियुक्ता भवतु । अवहननाधिकरणत्वेन प्राप्तखेदा न भवत्वित्यर्थः । अथ अवहननाधारभूतायाः पृथिव्या अनुग्रहानन्तरं सुकृतस्य यागादिजन्यस्य पुण्यस्य फलभूतं लोकं वयं गच्छेम प्राप्नुयाम ॥

नवमी ॥

एतौ ग्रावाणौ सयुजा युङ्ग्धि चर्मणि निर्भिन्ध्यंशून् यजमानाय साधु ।
अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥ ९ ॥

एतौ । ग्रावाणौ । सऽयुजा । युङ्ग्धि । चर्मणि । निः । भिन्धि । अंशून् ।
यजमानाय । साधु ।
अवऽघ्नती । नि । जहि । ये । इमाम् । पृतन्यवः । ऊर्ध्वम् । प्रऽजाम् ।
उत्ऽभरन्ती । उत् । ऊह ॥ ९ ॥

हे ऋत्विक् एतौ पुरोवर्तिनौ ग्रावाणौ अश्मवद्[1] दृढतरौ उलूखलमुसलौ सयुजा सयुजौ एकस्मिन् अवहननकर्मणि सह युञ्जानौ व्याप्रियमाणौ मित्रभूतौ वा चर्मणि अवहननार्थम् आस्तीर्णे आनडुहेऽजिने युङ्ग्धि योजय स्थापय । ⌛युजिर् योगे । लेटि "सेर्ह्यपिच्च" इति हिरादेशः । तस्य ङित्त्वात् "श्नसोरल्लोपः" इति अकारलोपे "हुझल्भ्यो[2] हेर्धिः" इति हेर्धिरादेशः ⌛ । अंशून् । उलूखलमुसलयोर्ग्रावत्वेन रूपणाद् व्रीहयः सोमांशुत्वेन रूप्यन्ते । सोमलताखण्डवद् यागनिर्वर्तकान् व्रीहीन् यजमानाय यजमानार्थं साधु शोभनं निर्भिन्धि युक्ताभ्याम् उलूख[लमुस]लाभ्याम् अवजहि वितुषीकुरु । ⌛भिदिर् विदारणे । पू-

1 S′ अश्ववद्. 2 S′ हुझलभ्य इति for हुझलभ्यो.

र्वेवल्लोण्मध्यमैकवचने रूपम्॥ । हे पत्नि अवघ्नती अवहननं कु-र्वती नि जहि निबाधस्व । के पुनस्ते निहन्तव्या इत्याह य इति । इ-माम् आत्मीयां प्रजां हन्तुं ये शत्रवः पृतन्यवः पृतनां सेनाम् आत्मन इच्छन्तः वर्तन्ते तान् नि जहीत्यर्थः । ॥पृतनाशब्दात् "सुप आ-त्मनः क्यच्" । "क्याच्छन्दसि" इति उप्रत्ययः । "कव्यध्वरपृतनस्यर्चि लोपः" इति आकारलोपः॥ । अपि च अवहननानन्तरम्[1] उद्भ-रन्ती मुसलम् ऊर्ध्वं हरन्ती । ॥"हृग्रहोर्भः॰" इति भत्वम्॥ । प्र-जाम् अस्मदीयाम् ऊर्ध्वम् उद् ऊह उन्नतं स्थानम् उद्गमय । श्रैष्ठ्यं गमयेत्यर्थः ॥

दशमी ॥

गृहाण ग्रावाणौ संकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।
त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥ १० ॥ (१)

गृहाण । ग्रावाणौ । संऽकृतौ । वीर । हस्ते । आ । ते । देवाः । यज्ञियाः । यज्ञम् । अगुः ।
त्रयः । वराः । यतमान् । त्वम् । वृणीषे । ताः । ते । सम्ऽऋद्धीः । इह । राधयामि ॥ १० ॥ (१)

हे वीर वीर्यवन् अध्वर्यो हस्ते स्वकीये पाणौ सुकृतौ शोभनकर्माणौ ग्रावाणौ उलूखलमुसलौ गृहाण स्वीकुरु । ॥ग्रह उपादाने । "हलः श्नः शानज्झौ" इति शानजादेशः॥ । ते* प्रसिद्धा यज्ञिया यज्ञार्हा देवास्त्वदीयं यज्ञम् आ अगुः आगमन् । ॥इण् गतौ । "इणो गा लुङि" इति गादेशः॥ । त्रयः त्रिसंख्याका वराः यजमानेन वर-यितव्याः प्रार्थनीयाः पदार्थाः । कर्मसमृद्धिः तत्फलभूता ऐहिकी समृद्धिः आमुष्मिकी समृद्धिरिति । हे यजमान त्वं यतमान् यादृग्विधान् वरान्

---

१ K $\overset{m}{K}$ सुकृतौ. Cs सकृतौ corrected into सुकृतौ. V सकृतौ. We with A B $\overset{h}{B}$ C D R $\overset{m}{S}$ P $\overset{2}{P}$ J Cp.

---

1 S′ आवाक्राहारानंतरम्.

वृणीषे प्रार्थयसे ते तव ताः प्राग् उदीरिता वरयितव्याः समृद्धीः इह अस्मिन् यज्ञे राधयामि संसाधयामि । ॥ राध साध संसिद्धौ ॥ ॥

[इति] एकादशे काण्डे प्रथमं सूक्तम् ॥

"इयं ते धीतिः" इति सूक्तस्य ब्रह्मौदनसवे पूर्वसूक्तेन सह उक्तो विनियोगः । तत्र "इयं ते धीतिः" इति प्रथमाया ऋचः पूर्वार्धर्चेन परापवनार्थं शूर्पं गृह्णीयात् । "परा पुनीहि" इति उत्तरार्धर्चेन तुषान् उदूहेत् । सूत्रितं हि । "इयं ते धीतिः [११] वर्षवृद्धम् [१२. ३. १९] "इति शूर्पं गृह्णाति । ऊर्ध्वं प्रजाम् [९] विश्वव्यचाः [१२. ३. १९] इ- "त्युदूहति । परा पुनीहि [११] इति तुषम्" इति [कौ° ८. २] ॥

"उपश्वसे" [१२] इति ऋचा तुषेभ्यस्तण्डुलान् [पृथक्] कुर्यात् । "उपश्वस इत्यपवेवेक्ति" इति हि [कौ° ८. २] सूत्रम् ॥

"परेहि नारि" [१३] इति ऋचा उदकम् आहरन्तीं पत्नीं संप्रेषयेत् । "एमा अगुः" [१४] इति ऋचः प्रथमपादेन आगच्छन्तीं पत्नीम् अनुमन्त्रयते । "उत्तिष्ठ नारि" इति पादद्वयेन पत्नीम् आह्वयेत् । "आ त्वागन् यज्ञः" इति पादैकदेशेन जलकुम्भदात्री पत्नी कर्तारं प्रेषयेत् । "प्रति कुम्भं गृभाय" इति अर्धपादेन पत्नी जलकुम्भं ग्राहयेत् कर्तारम् । तत्रैव कर्मणि "ऊर्जो भागः" [१५] इति ऋचः प्रथमपादेन जलकुम्भं भूमौ निदध्यात् । "ऋषिप्रशिष्टा[1]पः" इति पादत्रयेण उदपात्रम् आस्तीर्णचर्मणि निदध्यात् । सूत्रितं हि । "परेहि नारीत्युदहृतं[2] संप्रेष्यति अप उपगताम् अलंकृताम् । "एमा अगुरित्यायतीम् अनुमन्त्रयते । उत्तिष्ठ नारीति पत्नीं संप्रेष्य- "ति । प्रति कुम्भं गृभायेति प्रतिगृह्णाति । ऊर्जो भाग इति निद- "धाति" इति "ऋषिप्रशिष्टा[1] [१५] इत्युदपात्रं चर्मणि निदधाति" इति च [कौ° ८. १] ॥

पैतृमेधिके चयन[3]नाख्ये कर्मणि "ऊर्जो भागः" इति ऋचा अस्थीनि अश्मभिः इष्टकाभिर्वा आच्छादयेत् ॥

---

1 S' °प्रसृष्ट°. 2 S' °उदाहृतं. We with *Kaus'ika*. 3 S' चयाना°.

"अग्ने चरुः" [१६] इति ऋचा चरुस्थालीम् अग्नावधिश्रयेत् । "अग्ने चरुरधिश्रयति" इति [कौ° ८.२] सूत्रात् ॥

तथा दर्शपूर्णमासयोश्चर्वधिश्रयणेपि एषा विनियुक्ता । सूत्रितं हि । "फलीकृतांस्त्रिः प्रक्षाल्य तण्डुलान् अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षद् इति चरुम् अधिनिदधाति" इति [कौ° १.२] ॥

ब्रह्मौदनसव एव "शुद्धाः पूताः" इति ऋचा अधिश्रिते चरुपात्रे उदकम् आसिञ्चेत् । "ब्रह्मणा शुद्धाः" इति ऋचा आसिक्तासु अप्सु तण्डुलान् आवपेत् । सूत्रितं हि । "शुद्धाः [पूताः][१७] पूताः पवित्रैः "[१२.३.२५] [इति पवित्रे] अन्तर्धायोदकम् आसिञ्चति । ब्रह्मणा "शुद्धाः[१८] [1]संख्याता [2]स्तोकाः[१२.३.२८] इत्यासिक्तान्निरुप्तांस्तण्डु-"लान्[2] आवपेत्" इति [कौ° ८.२] ॥

"तथा दर्शपूर्णमासयोश्चरुस्थाल्याम् उदकासेचने तण्डुलावापे च "शुद्धाः पूताः" "ब्रह्मणा शुद्धाः" इत्येते ऋचौ विनियुक्ते । सूत्रितं हि । "शुद्धाः पूता इत्युदकम् आसिञ्चति ब्रह्मणा शुद्धा इति तण्डुलान्" इति [कौ° १.२] ॥

"उरुः प्रथस्व" इति ऋचा चरुं श्रपयेत् । "उरुः प्रथस्व[१९] उद्योधन्ति[१२.३.२९] इति श्रपयति" इति [कौ° ८.२] सूत्रात् ॥

तथा तत्रैव कर्मणि "उरुः प्रथस्व" इत्येषा दातृवाचने विनियुक्ता । "उरुः प्रथस्व महता महिम्ना[१९] इदं मे ज्योतिः[२८] सत्याय[१२.३.४६-४८] इति तिस्रः" [कौ° ८.९] इति सूत्रात् ॥

तत्र प्रथमा ॥

इ॒यं ते॑ धी॒तिरि॒दमु॑ ते ज॒नित्रं॑ गृ॒ह्णातु॒ त्वामदि॑तिः॒ शूर॑पुत्रा ।
परा॑ पुनीहि॒ य इ॒मां पृ॑तन्यवो॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥ ११ ॥

इ॒यम् । ते॒ । धी॒तिः । इ॒दम् । ऊं॒ इति॑ । ते॒ । ज॒नित्र॑म् । गृ॒ह्णातु॑ । त्वाम् । अदि॑तिः । शूर॑ऽपुत्रा ।

1 S′ असंख्याताः. 2 S′ स्तोकात्यासिक्तानिरुक्तांस्तंडुलान्. *Kaus′ika*: इत्यायस्त्वासुनीकतंडुलान्. The क्त may be क्त.

परा । पुनीहि । ये । इमाम् । पृतन्यवः । अस्यै । रयिम् । सर्वऽवीरम् ।
नि । यच्छ ॥ ११ ॥

हे शूर्प ते तव यत् परापवनं तण्डुलेभ्यस्तुषविवेचनम् इयमेव धीतिः पानम् । धेट् पाने । अस्माद् भावे क्तिन् । "घुमास्था°" इति ईत्वम् । इदमु इदमेव परापवनकर्म ते तव जनित्रम् जननिमित्तं कारणम् । एवंविधं त्वा त्वां शूरपुत्रा शूराः शौर्योपेता मित्रवरुणधातृप्रभृतयः पुत्रा यस्याः सा अदितिः अदीना देवमाता गृह्णातु परापवनार्थं हस्ते धारयतु । ये शत्रवः इमां पत्नीं हिंसितुं पृतन्यवः पृतनां सेनाम् आत्मन इच्छवो भवन्ति तान् निरसितुं परा पुनीहि अवहतेभ्यो[1] व्रीहिभ्यस्तुषान् पृथक् कुरु । पूञ् पवने । "प्वादीनां ह्रस्वः" इति ह्रस्वत्वम् । अस्यै पत्न्यै [सर्ववीरम्] सर्वैर्वीरैः पुत्रपौत्रादिभिरुपेतं [रयिम्] धनं नि यच्छ नितरां प्रयच्छ ॥

द्वितीया ॥

उपश्वसे द्रुवये[1] सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।
श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥ १२ ॥

उपऽश्वसे । द्रुवये । सीदत । यूयम् । वि । विच्यध्वम् । यज्ञियासः । तुषैः ।
श्रिया । समानान् । अति । सर्वान् । स्याम । अधःऽपदम् । द्विषतः ।
पादयामि ॥ १२ ॥

ध्रुवये* ध्रुवाय स्थिराय सत्यफलाय कर्मणे हे तण्डुलाः युष्मान् उपश्वसे उप समीपे आश्वासयामि प्रभूतान् करोमि । यागे विनियोक्ष्य इत्यर्थः । श्वस प्राणने इति धातुः । ध्रु गतिस्थैर्ययोः इत्यस्माद् औणादिकः किप्रत्ययः । अतो यूयं सीदत शूर्पे उपविशत । यज्ञियासः* यज्ञिया यज्ञार्हा यूयं तुषैर्वि विच्यध्वम् विविक्ताः पृथक्कृता भवत । विचिर् पृथग्भावे[2] इति धातुः । वयमपि युष्मज्जनि-

१ A B D K K[m] S[m] E V Cs ध्रुवये. We with B[h] C R P P[2] J Cp and Sâyaṇa's text in S′.

1 S′ °हितेभ्यो. 2 S′ °भागे.

तया श्रिया संपदा सर्वान् समानान् समानजन्मनः पुरुषान् अति स्याम अतिक्रान्ता भवेम । द्विषतः द्वेष्टॄन् शत्रून् अधस्पदम् पादयोरधस्तात् पादयामि क्षिपामि । ⧗ "अधःशिरसी पदे" इति विसर्जनीयस्य सत्वम् ⧗ ॥

तृतीया ॥

परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठोऽध्यरुक्षद् भराय ।
तासां गृह्णीताद् यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात् ॥१३॥

परा । इहि । नारि । पुनः । आ । इहि । क्षिप्रम् । अपाम् । त्वा । गोऽस्थः । अधि । अरुक्षत् । भराय ।
तासाम् । गृह्णीतात् । यतमाः । यज्ञियाः । असन् । विऽभाज्य । धीरी । इतराः । जहीतात् ॥ १३ ॥

उदकाहर्त्री प्रेष्यते । हे नारि परा इहि परागच्छ उदकाहरणार्थं पराङ्मुखी जलाशयं गच्छ । तत्र जलं गृहीत्वा क्षिप्रम् शीघ्रं पुनरेहि पुनरागच्छ । तस्मिन् समये त्वा त्वाम् अपाम् उदकानां गोष्ठः । गावस्तिष्ठन्ति पानार्थम् अस्मिन्निति गोष्ठो जलराशिः । ⧗ "घञर्थे कविधानम्" इति अधिकरणे कप्रत्ययः । "अम्बाम्बगोभूमि°" इति षत्वम् ⧗ । भराय भरणार्थम् अध्यरुक्षत् अधिरोहतु । शिरसि आरोहतु । ⧗ रुह बीजजन्मनि प्रादुर्भावे । "शल इगुपधाद् अनिटः क्सः" इति क्सप्रत्ययः ⧗ । तासां प्राप्तानाम् अपां मध्ये यतमाः यादृश्य आपो यज्ञियाः यज्ञार्हा आसन्[1] अभवन् ता गृह्णीतात् घटादिना गृहाण । ⧗ ग्रह उपादाने । "तुह्योस्तातङ् आशिष्यन्यतरस्याम्" इति हेस्तातङ् आदेशः ⧗ । यद्वा । इदानीं बहुवद् उच्यते । हे उदकाहर्त्र्यो नार्यः गृह्णीतात् गृह्णीत घटादिपात्रेषु उदकं पूरयत । ⧗ "तस्य तात्" इति तशब्दस्य तात् आदेशः । यतमा इति । "वा बहूनां

१ E B^h C गोष्ठो अध्य°. We with A B D K K^m R S^m V Cs. २ A R K V आसन्. We with B^h C D S^m P P^2 J E Cs.

1 Sâyaṇa's text in S' too has आसन्.

जातिपरिप्रश्ने डतमच्'' इति यच्छब्दात् डतमच् प्रत्ययः ⧗ । इतरा अयज्ञिया अपः धीरी धीमती त्वं विभाज्य यज्ञियाभ्यो विविच्य जहीतात् जहीहि परित्यज । ⧗ ओहाक् त्यागे । तातङि "घुमास्था०" इति ईत्वम् ⧗ ॥

चतुर्थी ॥

एमा अंगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं[1] रभस्व ।

सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥

आ । इमाः । अगुः । योषितः । शुम्भमानाः । उत् । तिष्ठ । नारि । तवसम्[1] । रभस्व ।

सुऽपत्नी । पत्या । प्रऽजया । प्रजाऽवती । आ । त्वा । अगन् । यज्ञः । प्रति । कुम्भम् । गृभाय ॥ १४ ॥

शुम्भमानाः शोभनालंकारयुक्ता इमा योषितः उदकाहर्त्र्यः स्त्रियः आ अगुः आगमन् । हे नारि पत्नि उत्तिष्ठ आसनाद् उत्थिता भव । ⧗ "०अनूर्ध्वकर्मणि" इति पर्युदासाद् आत्मनेपदाभावः ⧗ । तव[*1] त्वाम् उपगतास्ताः सं[*] रभस्व संग्रहीतुम् उद्युक्ता भव । ⧗ रभ राभस्ये । राभस्यं कार्योपक्रम इति तद्व्याख्या ⧗ । पत्या शोभनपतिना सुपत्नी पत्नीनां श्रेष्ठतमा । यद्वा पत्या गुणाधिकेन पुरुषेण शोभनपतिका । ⧗ "विभाषा सपूर्वस्य" इति ङीम्नकारौ ⧗ । प्रजया पुत्रादिरूपया प्रजावती शोभनपुत्रयुक्ता । भवेत्यर्थः । ईदृशीं[2] त्वा त्वां यज्ञः आ अगन् उदकरूपेण प्रापत् । ⧗ गमेर्लुङि "मन्त्रे घस०" इति च्लेर्लुक् । "हल्ङ्या०" इत्यादिलोपे "मो नो धातोः" इति नत्वम् ⧗ । कुम्भम् उदकपूर्णघटं प्रति गृभाय प्रतिगृहाण आदत्स्व । ⧗ ग्रहेर्लोण्मध्यमैकवचने "छन्दसि शायजपि" इति श्नाप्रत्ययस्य शायजादेशः । "हृग्रहोर्भः०" इति भत्वम् ⧗ ॥

---

१ So A B B[h] C D K K[m] R S[m] P P[2] E J Cs. Sâyaṇa तव and सम् separately, which is inferior to the reading of our authorities.

---

1 Here Sâyaṇa's reading is inferior to ours. See note १ above. 2 S′ ईदृशी.

पञ्चमी ॥

ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।
अयं यज्ञो गातुविन्नाथवित् प्रजाविदुग्रः पशुविद् वीरविद् वो अस्तु॥१५॥

ऊर्जः । भागः । निऽहितः । यः । पुरा । वः । ऋषिऽप्रशिष्टा । अपः । आ । भर । एताः ।

अयम् । यज्ञः । गातुऽवित् । नाथऽवित् । प्रजाऽवित् । उग्रः । पशुऽवित् । वीरऽवित् । वः । अस्तु ॥ १५ ॥

हे आपः वः युष्माकम् ऊर्जः बलकरस्य सारभूतस्य जलराशेर्यो भागः अंशः पुरा पूर्वं निहितः ब्रह्मणा परिकल्पितः । स एव अत्राहृत्य निधीयत इति शेषः । हे पत्नि एताः आहृताः सारभूता अपः ऋषिप्रशिष्टा ऋषिणा मन्त्रेण अतीन्द्रियार्थदर्शिना ब्रह्मणा वा प्रशिष्टा अनुशिष्टा अनुज्ञाता [त्वम्] आ भर आस्तीर्णे चर्मणि आहर । स्थापयेत्यर्थः । ऋषिप्रशिष्टेति । शासु अनुशिष्टौ । अस्मात् कर्मणि निष्ठा । "शास इदङ्हलोः" इति इत्वम् ॥ अयं क्रियमाणः ब्रह्मौदनसवाख्यो यज्ञः गातुवित् गातोः स्वर्गमार्गस्य लम्भकः । नाथवित् नाथ्यमानस्य[1] आशंसनीयस्य स्वर्गादिफलस्य लम्भयिता । यद्वा नाथः स्वामी तस्य लम्भकः । प्रजावित् प्रजायन्त इति प्रजाः पुत्रपौत्रादिरूपाः तासां लम्भकः । उग्रः उद्गूर्णबलः । परैरनभिभवनीय इत्यर्थः । पशुवित् पशूनां गवाश्वादीनां लम्भयिता । वीरवित् विविधम्[2] ईर्यन्ते तत्तत्कर्मणि[3] प्रेष्यन्त इति वीराः कर्मकरास्तेषां लम्भयिता हे यजमानपत्न्यादयः वः युष्मभ्यम् एवंविधफलप्रदः अस्तु भवतु ॥

षष्ठी ॥

अग्नौ चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥ १६ ॥

१ P निऽहिताः. We with P J Cp.

1 S' नाथमानस्य. 2 S' धम् for विविधम्. 3 S' तत्कर्म° for तत्तत्कर्म°.

अग्ने । चरुः । यज्ञियः । त्वा । अधि । अरुक्षत् । शुचिः । तपिष्ठः । तपसा । तप । एनम् ।
आर्षेयाः । दैवाः । अभिऽसंगत्य । भागम् । इमम् । तपिष्ठाः । ऋतुऽभिः । तपन्तु ॥ १६ ॥

हे अग्ने त्वा त्वां यज्ञियः यज्ञार्हः चरुः हविःश्रपणार्था स्थाली अध्यरुक्षत् अधिरोहतु उपरि तिष्ठतु । शुचिः शुद्धो निर्मलः तपिष्ठः तप्तृतमः । ॥ तप्तृशब्दात् "तुश्छन्दसि" इति इष्ठनि "तुरिष्ठेमेयस्सु" इति तृलोपः ॥ । तपसा संतापकेन आत्मीयेन तेजसा एनं चरुं तप तप्तं कुरु । आर्षेयाः । गोत्रप्रवर्तकान् ऋषीन् ये विदुस्ते आर्षेया ब्राह्मणाः । दैवाः । [देवाः] होतव्या इन्द्रादयः तत्संबन्धिजना दैवाः । ते उभये स्वंस्वं भागम् अंशम् अभिसंगत्य अभिप्राप्य इमं चरुं तपिष्ठाः तप्तृतमाः सन्तः ऋतुभिः वसन्तादिभिः कालविशेषैः तपन्तु तप्तं कुर्वन्तु ॥

सप्तमी ॥

शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।
अदुः प्रजां बहुलान्[१] पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥ १७ ॥

शुद्धाः । पूताः । योषितः । यज्ञियाः । इमाः । आपः । चरुम् । अव । सर्पन्तु । शुभ्राः ।
अदुः । प्रऽजाम् । बहुलान् । पशून् । नः । पक्ता । ओदनस्य । सुऽकृताम् । एतु । लोकम् ॥ १७ ॥

शुद्धाः निर्मलाः पूताः पवित्राभ्याम् उत्पूता उत्पवनाख्यसंस्कारेण पवित्रीकृताः योषितः योषिद्रूपा मिश्रयित्र्यो वा यज्ञियाः यज्ञार्हाः शुभ्राः शुक्लवर्णा इमाः आहृता आपश्चरुम् अव सर्पन्तु स्थालीं प्रविशन्तु । ता आपो नः अस्मभ्यं प्रजाम् पुत्रादिरूपां बहुलान् अनेकविधान् गोमहिषाद्यांश्च पशून् अदुः ददतु प्रयच्छन्तु ॥ ओदनस्य ब्रह्मौदनाख्यस्य प-

१ A B^h C D K K^m बहुलांपशू॰. We with R S^m E V Cs.

क्ता* पाचको यजमानः । ▯पचेः “अन्येभ्योपि दृश्यन्ते” इति क्वनिप्▯ । सुकृताम् पुण्यकृतां लोकम् सुखोपभोगस्थानं स्वर्गादिकम् एतु गच्छतु ॥

अष्टमी ॥

ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
अपः[१] प्र विशत[२] प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत[३] लोकम् ॥ १८ ॥

ब्रह्मणा । शुद्धाः । उत । पूताः । घृतेन । सोमस्य । अंशवः । तण्डुलाः[४] । यज्ञियाः । इमे ।
अपः । प्र । विशत । प्रति । गृह्णातु । वः । चरुः । इमम् । पक्त्वा । सुऽकृताम् । एत[५] । लोकम् ॥ १८ ॥

ब्रह्मणा मन्त्रेण शुद्धाः निर्दोषाः उत अपि च घृतेन क्षरणशीलेन उदकेन पूताः प्रक्षालिताः । यद्वा श्रपणानन्तरभाविना अभिघारणेनाज्येन पूताः पवित्रीकृताः सोमस्य अमृतमयस्य अंशवः लताखण्डाः । तदात्मका इत्यर्थः । “निर्भिन्ध्यंशून्” इति हि प्राग्[९] उक्तम् । अत एव यज्ञियाः यज्ञार्हा इमे तण्डुलाः यूयम् अपः स्थालीगतानि उदकानि प्र विशत । चरुः स्थाली च वः युष्मान् प्रति गृह्णातु स्वीकरोतु । इमम् ओदनं पक्त्वा । ओदनपाकेन ब्रह्मौदनसवाख्यं कर्म लक्ष्यते । एतत् कर्म कृत्वेत्यर्थः । व्याख्यातम् अन्यत् ॥

नवमी ॥

उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।
पितामहाः पितरः प्रजोपजाहं पक्ता[६] पञ्चदशस्ते अस्मि ॥ १९ ॥

उरुः । प्रथस्व । महता । महिम्ना । सहस्रऽपृष्ठः । सुऽकृतस्य । लोके ।

१ B आपः. We with A B[h] C D K K[m] V R S[m] E Cs. २ B °विंशतु. We with A B[h] C D K K[m] R S[m] E V Cs. ३ K V Cs सुकृतामेतु. We with A B B[h] C D K[m] R S[m] E. ४ P तंदुलाः. We with P[2] J Cp. ५ K एतु. We with P P[2] J Cp. ६ B[h] C K[m] पक्त्वा. We with A D R S[m] K P P[2] J E V Cs.

पितामहाः । पितरः । प्रऽजा । उपऽजा । अहम् । पक्ता । पञ्चऽदशः । ते । अस्मि ॥ १९ ॥

हे ओदन सुकृतस्य पुण्यस्य फलभूते लोके स्वर्गादौ महता अधिकेन महिम्ना माहात्म्येन उरुः विस्तीर्णः सहस्रपृष्ठः सहस्रावयवः सन् प्रथस्व विस्तीर्णो भव । [1]अस्मदीयाः पितरः[1] पितामहाः । उपलक्षणम् एतत् । पितृपितामहाद्याः सप्तपुरुषा हे ओदन त्वया तृप्यन्ते । तथा प्रजा पुत्रदुहितृरूपा उपजा तत्पुत्रादिरूपा । एतदपि उपलक्षणम् । अनन्तराः पुत्राद्याः सप्तपुरुषास्त्वया प्रीयन्ते । एतदुभयापेक्षया पक्ता ब्रह्मौदनस्य पक्ता अहं ते तव पञ्चदशः पञ्चदशसंख्यापूरकः अस्मि भवामि । मदनुष्ठितेन अनेन यज्ञेन एते सर्वे प्रीयन्त इत्यर्थः ॥

दशमी ॥

सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान्मह्यमेव ॥ २० ॥ (२)

सहस्रऽपृष्ठः । शतऽधारः । अक्षितः । ब्रह्मऽओदनः । देवऽयानः । स्वःऽगः । अमून् । ते । आ । दधामि । प्रऽजया । रेषय । एनान् । बलिऽहाराय । मृडतात् । मह्यम् । एव ॥ २० ॥ (२)

सहस्रपृष्ठः सहस्रशरीरः शतधारः शतसंख्याकाभिर्धाराभिरमृतमयीभिर्युक्तः अक्षितः अक्षीयमाणः । भुज्यमानोपि क्षयम् अप्राप्नुवन्नित्यर्थः । देवयानः देवान् इन्द्रादीन् यान्ति गच्छन्ति पुण्यकृतः अनेनेति देवयानः । देवत्वप्राप्तिसाधनभूत इत्यर्थः । तथा स्वर्गः फलभूतं स्वर्गं प्रति अन्तरङ्गसाधनत्वात् तदात्मकोयम् इत्यर्थः । हे यजमान त्वया क्रियमाणोयं ब्रह्मौदनः एतत्संज्ञकः सवयज्ञः । उक्तगुणविशिष्टो भवतीत्यर्थः ।

१ So P P̊ J. Cp पक्त्वा. २ V K रेशयै°. We with A B̊ C D K̊ R S̊ K E Cs. ३ So P P̊ J Cp.

1 S′ अस्मदीयान पितरः.

अपि च ते तव बलिहाराय बलिः उपायनद्रव्यं तद्धरणार्थम् अमून् प्रसिद्धान् सजातान् आ दधामि अभिमुखं स्थापयामि । एनान् प्रजया पुत्रभृत्यादिरूपया रेशँय लेशय अल्पीकुरु । उपक्षीणान् कुर्वित्यर्थः । लिश अल्पीभावे । रलयोः एकत्वस्मरणाद् रेफः । मह्यमेव मामेव प्राग् उदीरितः सवयज्ञः मृळँतात् मृडयतु सुखयतु सर्वोत्कृष्टं करोतु । मृड सुखने । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाद् अस्मदश्चतुर्थी ॥

[इति एकादशकाण्डे] द्वितीयं सूक्तम् ॥

"उदेहि वेदिम्" इति सूक्तस्य ब्रह्मौदनसवे "अग्ने जायस्व" [११.१] इत्यनेन सह उक्तो विनियोगः ॥

तत्र "उदेहि वेदिम्" इति प्रथमया चरोरुद्वासनं कुर्यात् । "अभ्यावर्तस्व" इत्यनया चरुस्थालीं प्रदक्षिणम् आवर्तयेत् । सूत्रितं हि । "उदेहि वेदिम् [२१] धर्ता ध्रियस्व [१२.३.३५] इत्युद्वासयति । अभ्यावर्तस्व [२२] इति कुम्भीं प्रदक्षिणम् आवर्तयेत्" इति [कौ° ८.२] ॥

"अदितेर्हस्तँम्" इति ऋचा स्रुचं वेद्यां सादयेत् । "अदितेर्हस्तं [२४] [1]सर्वान्त्समागाः [१२.३.३६] इति मन्त्रोक्तम्" इति [कौ° ८.३] सूत्रात् ॥

"शृतं त्वा हव्यम्" [२५] इति ऋचा चतुर आर्षेयान् आसने उपवेशयेत् । सूत्रितं हि । "शृतं त्वा हव्यम् इति चतुर आर्षेयान् भृग्वङ्गिरोविद उपसादयति" इति [कौ° ८.४] ॥

"सोम राजन्" [२६] इति ऋचा चतुर आर्षेयान् ऋत्विजो यजमान आह्वयेत् । "शुद्धाः पूताः" [२७] इति ऋचा तेषाम् ऋत्विजां हस्तप्रक्षालनार्थम् उदकं दद्यात् । "शुद्धाः पूता इति मन्त्रोक्तम्" इति [कौ° ८.४] सूत्रात् ॥

"इदं मे ज्योतिः" इति ऋचा ओदने हिरण्यं निदध्यात् । सूत्रितं हि । "इदं मे ज्योतिः [२८] समग्नयः [१२.३.५०] इति हिरण्यमधिं[2]निदधाति" इति [कौ° ८.३] ॥

---

1 S' सर्वसमागादिति. We with *Kaus'ika*. 2 S' हिरण्यमभि°. We with *Kaus'ika*.

अत्र "इदं मे ज्योतिः" इति प्रथमपादं दातारं वाचयन् हिरण्यम् अधिनिदध्यात् । "कृण्वे पन्थाम्" इति "चरमपादं च दातारं वाचयेत्" इति हि भाष्यकारः[1] ॥

"पक्कं क्षेत्रात्" इति मध्यमेन पादद्वयेन बर्हिष्यासादितम् ओदनम् ईषत् कर्षयेत् । "पक्कं क्षेत्रात्[२८] वर्षं वनुष्व[१२.३.५३] इत्युपक[2]र्षयति" इति हि [कौ॰८.४] सूत्रम् ॥

"इदं मे ज्योतिः" इति समस्ता ऋक् दातृवाचने विनियुक्ता । "इदं मे ज्योतिः[२८] सत्याय[१२.३.४६-४८] इति तिस्रः" इति हि सूत्रम् [कौ॰८.९] ॥

"अग्नौ तुषान्"[२९] इति ऋचः प्रथमपादेन अग्नौ तुषान् जुहुयात् । "अग्नौ तुषान् इति तुषान् आवपति" इति [कौ॰८.४] सूत्रात् ॥

"परः कम्बूकान्" इति शेषेण पादत्रयेण फलीकरणान् उदूह[येत् । "परः कम्बूकान् इति सव्येन पादेन फलीकरणान् अपोह]यति" इति [कौ॰८.४] सूत्रम् ॥

"श्राम्यतः"[३०] इत्यादिका ऋचः ओदनसंपाते विकल्पेन विनियुक्ताः । सूत्रितं हि । "सूक्तेन पूर्वं संपातवन्तं करोति श्राम्यत इतिप्रभृतिभिर्वा" इति [कौ॰८.४] ॥

तत्र प्रथमा ॥

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।
श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥ २१ ॥

उत्ऽएहि । वेदिम् । प्रऽजया । वर्धय । एनाम् । नुदस्व । रक्षः । प्रऽतरम् । धेहि । एनाम् ।

श्रिया । समानान् । अति । सर्वान् । स्याम । अधःऽपदम् । द्विषतः । पादयामि ॥ २१ ॥

हे पक्कौदन वेदिम् हविरासादनाय प्रोक्षणादिबर्हिस्तरणादिसंस्कारसं-

1 This is not found in Kes'ava. So the author referred to must be Dârila.
2 So S'. *Kaus'ika*: अपकर्षति.

स्कृतां भूमिं प्रति उदेहि उदागच्छ । अग्नेः सकाशाद् उत्थाय वेद्याम् आसीदेत्यर्थः । एनां पत्नीं प्रजया पुत्रादिरूपया वर्धय समृद्धां कुरु । रक्षः यज्ञविघातकं राक्षसं नुदस्व अस्मात् स्थानात् प्रेरय प्रच्यावय । ⌛ नुद प्रेरणे ⌛ । तथा एनां पत्नीं प्रतरम् प्रकृष्टतरं[1] यथा भवति तथा धेहि धारय पोषय वा । ⌛ डुधाञ् धारणपोषणयोः । "घ्वसोरेद्धावभ्यासलोपश्च" इति एत्त्वाभ्यासलोपौ ⌛ । श्रिया समानान् इति उत्तरोर्धर्चो व्याख्यातः [१२] ॥

द्वितीया ॥

अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां[१] देवताभिः सहैधि ।
मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥ २२ ॥

अभिऽआवर्तस्व । पशुऽभिः । सह । एनाम् । प्रत्यङ् । एनाम्[२] । देवताभिः । सह । एधि ।
मा । त्वा । प्र । आपत् । शपथः । मा । अभिऽचारः । स्वे । क्षेत्रे । अनमीवा[३] । वि । राज ॥ २२ ॥

हे ब्रह्मौदन एनान्* पत्नीयजमानादीन् पशुभिः लब्धव्यैर्गोमहिषाद्यैः सह अभ्यावर्तस्व अभिलक्ष्य आवृत्तो भव । तथा एनान्* यष्टव्याभिर्देवताभिः सह प्रत्यङ् प्रत्यञ्चन् आभिमुख्येन गच्छन् एधि भव ॥ हे यजमान यद्वा हे पत्नि शपथः परकृत आक्रोशस्त्वा त्वां मा प्रापत् मा प्राप्नोतु । ⌛ आप्लृ व्याप्तौ । माङि लुङि लृदित्वात् च्लेः अङ् आदेशः ⌛ । तथा परकृतः अभिचारः मारणकर्म मा प्राप्नोतु । तथा स्वे स्वकीये क्षेत्रे स्थाने अनमीवा अमीवा रोगस्तद्रहिता सती वि राज विशेषेण राजमाना भव । ⌛ राजतिः ऐश्वर्यकर्मा ⌛ ॥

तृतीया ॥

ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।

---

१ A प्रत्यगें°. $\overset{h}{B}$ प्रत्यङ्ङुं°. Cs प्रत्यङें° corrected into प्रत्यङे. We with B C D K $\overset{m}{K}$ R $\overset{m}{S}$ E. २ So P $\overset{2}{P}$ J Cp. ३ P $\overset{2}{P}$ Cp अनमीवाः ।. J अनमीवा । changed to अनमीवाः ।.

---

1 S′ inserts धनं after प्रकृष्टतरं.

अंसुद्रीं[1] शुद्धामुप धेहि नारि तत्रौदुनं सादय दैवानाम्[2] ॥ २३ ॥

ऋतेन । तष्टा । मनसा । हिता । एषा । ब्रह्मऽओदुनस्य । विऽहिता । वेदिः । अग्रे ।

अंसुद्रीम्[3] । शुद्धाम् । उप । धेहि । नारि । तत्र । ओदुनम् । सादय । दैवानाम् ॥ २३ ॥

ऋतेन सत्येन ब्रह्मणा तष्टा तनूकृता सम्यङ्निर्मिता । तक्षू त्वक्षू तनूकरणे । कर्मणि निष्ठा । "यस्य विभाषा" इति इट्प्रतिषेधः । "स्कोः संयोगाद्योः०" इति कलोपः । मनसा प्रथमसृष्टेन हैरण्यगर्भेण हिता धारिता । "दधातेर्हिः" इति निष्ठायां हिरादेशः । एषा एवंगुणविशिष्टा वेदिः ब्रह्मौदनस्य सादनाय अग्रे पुरा विहिता महर्षिभिः[1] कल्पिता । हे नारि पत्नि अंशध्रीम्* अंशान् भागान् देवमनुष्यपितृसंबन्धिनो धारयतीति अंशध्री तां शुद्धाम् अनुपहतां वेदिम् उप धेहि उप समीपे धारय । तत्र वेद्यां पक्वम् इमं देवानां* स्वभूतम् ओदनं सादय प्रापय । आसादयेत्यर्थः ॥

चतुर्थी ॥

अदितेर्हस्तां[4] स्रुचमेतां द्वितीयां सप्तऋषयो[5] भूतकृतो यामकृण्वन् ।
सा गात्राणि विदुष्योदुनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥ २४ ॥

अदितेः । हस्ताम्[6] । स्रुचम् । एताम् । द्वितीयाम्[6] । सप्तऽऋषयः । भूतऽकृतः । याम् । अकृण्वन् ।

सा । गात्राणि । विदुषी । ओदुनस्य । दर्विः । वेद्याम् । अधि । एनम् । चिनोतु ॥ २४ ॥

१ B^h C K अंसध्रीं. V अंशध्रीं. We with A B D R S^m E Cs. २ V K देवानाम्. We with A B B^h C D K^m R S^m P P^2 J E Cs. ३ So we with P P^2 J Cp. ४ K V हस्तं. We read हस्तां and द्वितीयां with A B B^h C D K^m R S^m E V. ५ E B S^m R C K^m सप्तर्षयो. We with A D Cs. ६ So we read with P P^2 J Cp.

1 S' महऋषिभिः.

अदितेः देवमातुः द्वितीयम्* द्वित्वसंख्यापूरकं हस्तम्* एतां होमसाधनभूतां यां स्रुचं भूतकृतः भूतानां प्राणिनां स्रष्टारः [सप्तऋषयः] अकृण्वन् अकुर्वन् सैषा दर्विः होमसाधनभूता स्रुक् ओदनस्य पक्वस्य गात्राणि शरीराणि तत्परूंषि च विदुषी जानती वेद्याम् अधि उपरि एनं ब्रह्मौदनं चिनोतु स्थापयतु ॥

पञ्चमी ॥

शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।
सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥ २५ ॥

शृतम् । त्वा । हव्यम् । उप । सीदन्तु । दैवाः । निःऽसृप्य । अग्नेः । पुनः । एनान् । प्र । सीद ।
सोमेन । पूतः । जठरे । सीद । ब्रह्मणाम् । आर्षेयाः । ते । मा । रिषन् । प्रऽअशितारः ॥ २५ ॥

हे ओदन शृतम् पक्वम् अत एव हव्यम् हवनयोग्यं त्वा त्वां देवा* उप सीदन्तु यष्टव्या देवा उपसन्ना भवन्तु । "शृतं पाके" इति निपात्यते । शृतस्यैव हविषो देवार्हता तैत्तिरीये स्पष्टम् आम्नायते । "यो विदग्धः स नैर्ऋतो योऽशृतः स रौद्रो यः शृतः स सदेवः" इति [तै॰ सं॰ २. ६. ३. ४] । हे तादृशौदन त्वम् अग्नेः सकाशात् निःसृप्य निर्गत्य पुनरेनान् प्र सीद प्राप्नुहि । सोमेन अमृतमयेन सोमरसेन क्षीरदध्यादिरूपेण । श्रूयते हि सोमात्मकत्वं दधिपयसोः । "सोमः खलु वै सांनाय्यम्" इति [तै॰ ब्रा॰ ३. २. ३. ११] । तेन पूतः शुद्धः सन् ब्रह्मणाम् ब्राह्मणानां जठरे उदरे सीद उपविश । आर्षेयाः स्वस्वगोत्रप्रवराभिज्ञा भृग्वङ्गिरोविदस्ते* ब्राह्मणा ओदनस्य प्राशितारः भोक्तारः मा रिषन् मा विनश्यन्तु । तेषाम् उदरे प्रविष्टस्त्वं हिंसां मा कृथा इत्यर्थः ॥

---

१ K V देवा. We with A B B^h C D K^m R S^m E V Cs. २ So P P^2 J Cp. ३ So P P^2 J Cp.

षष्ठी ॥

सोमं राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीनार्षेयांस्तपसोधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥ २६ ॥

सोम । राजन् । सम्ऽज्ञानम् । आ । वप । एभ्यः । सुऽब्राह्मणाः । यतमे । त्वा । उपऽसीदान् ।
ऋषीन् । आर्षेयान् । तपसः । अधि । जातान् । ब्रह्मऽओदने । सुऽहवा । जोहवीमि ॥ २६ ॥

हे राजन् राजमान सोम तदात्मक ब्रह्मौदन एभ्यः भोक्तृभ्यो ब्राह्मणेभ्यः । तादर्थ्ये चतुर्थी । संज्ञानम् सम्यग् ज्ञानम् आ वप निधेहि । मोहं मा कृथा इत्यर्थः । यतमे यज्जातीयाः सुब्राह्मणाः शोभना ब्राह्मणा भृग्वङ्गिरोविदः त्वा त्वाम् उपसीदान् उपसन्ना भवन्ति । सीदतेर्लेटि आडागमः । यतमे इति । "वा बहूनां जातिपरिप्रश्ने डतमच्" इति डतमच् प्रत्ययः । तस्य सर्वनामगणे पाठात् तदन्तस्य सर्वनामसंज्ञायां जसः शीभावः । एभ्य इति पूर्वत्र संबन्धः । अपि च तपसोधि जातां* दीक्षारूपात् तपस उत्पन्ना । "ब्रह्मणो वा एष जायते यो दीक्षते" इति हि ब्राह्मणम् [आप॰ १०. ११. ६] । एवंभूता सुहवा शोभनाह्वाना पत्नी आर्षेयान् प्रागुक्तलक्षणान् ऋषीन् ब्रह्मौदने विषये जोहवीमि पुनःपुनराह्वयामि । ह्वयतेर्यङ्लुगन्तात् लटि उत्तमैकवचने "ह्वः संप्रसारणम्" "अभ्यस्तस्य च" इति संप्रसारणम् । "गुणो यङ्लुकोः" इति अभ्यासस्य गुणः ॥

सप्तमी ॥

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदमभिषिञ्चामि वोहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥ २७ ॥

शुद्धाः । पूताः । योषितः । यज्ञियाः । इमाः । ब्रह्मणाम् । हस्तेषु । प्रऽपृथक् । सादयामि ।

यत्ऽकामः । इदम् । अभिऽसिञ्चामि । वः । अहम् । इन्द्रः । मरुत्वान् ।
स: । ददात् । इदम् । मे ॥ २७ ॥

शुद्धाः निर्मलाः पापरहिताः पूताः स्वसंसर्गेण अन्यस्यापि पावयित्र्यः योषितः स्त्रीरूपा मिश्रणशीला वा यज्ञियाः यज्ञार्हा इमाः एवंगुणविशिष्टा अपः ब्रह्मणाम् प्रागुदीरितलक्षणानां ब्राह्मणानां हस्तेषु पाणिषु । अत्र प्र इत्युपसर्गः उपसृष्टां क्रियाम् आह । प्रक्षालनक्रियाव्याजेनेत्यर्थः । प्रकर्षेण [वा] पृथक् सादयामि । सांकर्यं यथा न भवति तथा विक्षिपामीत्यर्थः । हे उदीरितलक्षणा आपः वः युष्मान् अहं यत्कामः यत् फलं कामयमानः इदम् इदानीम् अभिषिञ्चामि अभितः क्षारयामि इदं काम्यमानं फलं सः प्रसिद्धो मरुत्वान् मरुद्गणैर्युक्त इन्द्रो मे मह्यं ददात् ददातु ॥

अष्टमी ॥

इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥ २८ ॥

इदम् । मे । ज्योतिः । अमृतम् । हिरण्यम् । पक्वम् । क्षेत्रात् । कामऽदुघा । मे । एषा ।
इदम् । धनम् । नि । दधे । ब्राह्मणेषु । कृण्वे । पन्थाम् । पितृषु । यः । स्वःऽगः ॥ २८ ॥

इदं निधीयमानं हिरण्यम् अमृतम् अविनश्वरं मे मम ज्योतिः प्रकाशः । स्वर्गमार्गस्य प्रकाशको दीप इत्यर्थः ॥ पक्वम् पाकेन संस्कृतम् एतद् अन्नम् क्षेत्रात् व्रीहियवादिसस्याढ्याद् भूप्रदेशाद् उत्पन्ना एषा [मे] कामदुघा कामानां दोग्ध्री धेनुः । ⌛ "दुहः कब्घश्च" इति कब्घत्वे ⌛ ॥ इदं धनं दक्षिणात्वेन दीयमानं ब्राह्मणेषु नि दधे निक्षिपामि यथा मम तत् स्वर्गे लोके कोटिगुणितं स्यात् । तथा पितृषु अस्म-

---

१ B omits the visarga in यः. We with A K $\overset{m}{K}$ $\overset{h}{B}$ C D E R $\overset{m}{S}$ V Cs.

दीयेषु पितृपितामहादिषु विषये यः प्रसिद्धस्तैरभिलषितः स्वर्गः पुण्यलोकः तस्य पन्थाम् पन्थानं कृण्वे करोमि ॥

नवमी ॥

अग्नौ तुषाना वप जातवेदसि परः कम्बूकाँ अप मृड्ढि दूरम् ।
एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम्[1] ॥ २९ ॥

अग्नौ । तुषान् । आ । वप । जातऽवेदसि । परः । कम्बूकान् । अप । मृड्ढि । दूरम् ।
एतम् । शुश्रुम । गृहऽराजस्य । भागम् । अथो इति । विद्म । निःऽऋतेः । भागऽधेयम् ॥ २९ ॥

हे ऋत्विक् जातवेदसि जातानां वेदितरि अग्नौ तुषान् ब्रह्मौदनार्थतण्डुलेभ्यः पृथक्कृतान् आ वप प्रक्षिप । तेषाम् अग्नौ प्रक्षेपः प्रतिपत्तिरित्यर्थः ॥ तथा[1] कम्बूकान् फलीकरणान् परः परस्ताद् दूरम् अप मृड्ढि पादेन अपमार्जनं कुरु । गृहराजस्य गृहाणाम् अधिपतेर्वास्तुनाथस्य । "राजाहःसखिभ्यः०" इति टच् । एतं कम्बूकाख्यं[2] भागं शुश्रुम अभिज्ञेभ्यो वयं श्रुतवन्तः । अथो अपि च निर्ऋतेः पापदेवताया भागधेयम् हविर्भागम् एतं विद्म जानीमः । "विदो लटो वा" इति मसो मादेशः । भागशब्दात् स्वार्थे धेयप्रत्ययः ॥

दशमी ॥

श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।
येन रोहात् परमापद्य यद् वय उत्तमं नाकं परमं व्योम ॥ ३० ॥ (३)

श्राम्यतः । पचतः । विद्धि । सुन्वतः । पन्थाम् । स्वःऽगम् । अधि । रोहय । एनम् ।
येन । रोहात् । परम् । आऽपद्य । यत् । वयः । उत्ऽतमम् । नाकम् । परमम् । विऽओम ॥ ३० ॥ (३)

---

१ B निर्ऋतेभाग°. We with A C D E K K^m B^h R S^m V Cs.

---

1 S′ यथा. 2 S′ कंबु°.

श्राम्यतः दीक्षारूपं तपस्तप्यमानान् । ⌛श्रमु तपसि खेदे च । अस्मात् लटः शत्रादेशः । "शमाम् अष्टानां दीर्घः श्यनि" इति दीर्घः ⌛ । दीक्षाजनितश्रमानन्तरं पचतः उक्तरीत्या ब्रह्मौदनपाकं कुर्वतः सुन्वतः सोमाभिषवं कुर्वतः । सवयज्ञ एव सोमयागत्वेन रूप्यते । सवयज्ञानुष्ठातॄन् यजमानान् हे ब्रह्मौदन त्वं विद्धि जानीहि । एनान्* यजमानान् स्वर्गम् स्वर्गप्रापकं पन्थाम् पन्थानं मार्गम् अधि रोहय उपरि आरोहय । उत्तमम् उत्कृष्टतमं नाकम् दुःखसंस्पर्शरहितं परमम् सर्वस्य परस्ताद् उपरि देशे वर्तमानं स्वर्गाख्यं यद् व्योमास्ति तद् येन पथा अयं यजमानो रोहात् रोहेत् आरूढो भवेत् । कथं भूत्वेत्याह । परम् उत्कृष्टं वयः पक्षिरूपं श्येनात्मकं यद्[1] अस्ति तद् आपद्य[1] आस्थाय । श्रूयते हि तैत्तिरीयके । "श्येनो वै वयसां पतिष्ठः । श्येन एव भूत्वा सुवर्गं लोकं पतति" इति [तै॰ सं॰ ५.४.११.१] । तं पन्थानम् आरोहयेति पूर्वत्रान्वयः ॥

[इति] तृतीयं सूक्तम् ॥

"बभ्रेरध्वर्यो" इति सूक्तस्य ब्रह्मौदनसवे "अग्ने जायस्व" [११.१] इत्यनेन सह उक्तो विनियोगः । तत्र "बभ्रेरध्वर्यो" इति ऋचा ओदनस्योपरि गर्तं कुर्यात् । सूत्रितं हि । "बभ्रेरध्वर्यो [३१] इदं मापम् [१२.३.४५] इत्युपर्यापानं[2] करोति" इति [कौ॰ ८.३] ॥

"घृतेन गात्रा" इति पादेन घृतेन ओदनं विष्यन्दयेत्[3] । "घृतेन "गात्रा [३१] आ सिञ्च सर्पिः [१२.३.४५] इति सर्पिषा विष्यन्द- "यति" इति [कौ॰ ८.३] सूत्रात् ॥

"कृण्वे पन्थाम्" इति चरमपादं दातारं वाचयेत् । "बभ्रे रक्षः" इत्यादिभिर्ऋग्भिः ओदनम् अनुमन्त्रयेत । "समाचिनुष्व" इत्यनया आज्यं जुहुयात् । "अग्ने प्रेहि [४.१४.५] समाचिनुष्व [३६] इत्याज्यं जुहुयात्" इति हि [कौ॰ ८.४] सूत्रम्[4] ॥

1 S′ यदिस्तदापद्य. 2 S′ °इत्यपर्या° for °इत्युपर्या°. We with *Kaus′ika*. 3 S′ निष्यन्द° for विष्यन्द°. We with *Kaus′ika*. 4 S′ सूत्रात्.

तत्र प्रथमा ॥

बभ्रेरध्वर्यो मुखमेतद् वि मृड्ढ्याज्याय लोकं कृणुहि[१] प्रविद्वान् ।
घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥ ३१ ॥

बभ्रेः । अध्वर्यो इति । मुखम् । एतत् । वि । मृड्ढि । आज्याय । लोकम् ।
कृणुहि । प्रऽविद्वान् ।
घृतेन । गात्रा । अनु । सर्वा । वि । मृड्ढि । कृण्वे । पन्थाम् । पितृषु । यः ।
स्वःऽगः ॥ ३१ ॥

हे अध्वर्यो अध्वरस्य नेतर्ऋत्विक् बभ्रेः भरणशीलस्य पोषकस्य पक्वस्य ओदनस्य । ⧖ डुभृञ् धारणपोषणयोः । "आदृगमहनजनः किकिनौ लिट् च" इति किप्रत्ययः ⧖ । तथाविधस्य ओदनस्य एतन्मुखम् उपरिप्रदेशं वि मृड्ढि विशेषेण मार्जय शोधय । ⧖ मृजूष् शुद्धौ । अस्मात् लोटि सेर्हिरादेशः । "हुझल्भ्यः॰" इति हेर्धित्वम् । अदादित्वात् शपो लुक् । "व्रश्च॰" इत्यादिषत्वे जश्त्वम् ⧖ । मुखविमार्जनानन्तरम् हे अध्वर्यो विद्वान् जानन् आज्याय । ⧖ षष्ठ्यर्थे चतुर्थी ⧖ । आज्यस्य धारणार्थं लोकम् स्थानं गर्तरूपं कृणुहि कुरु ओदनमध्ये कल्पय । ⧖ कृवि हिंसाकरणयोश्च । "धिन्विकृण्व्योर च" इति उप्रत्ययः । "उतश्च प्रत्ययाच्छन्दसि वा वचनम्" इति हेर्लुगभावः ⧖ । तथा सर्वा सर्वाणि गात्रा गात्राणि स्थालीगतस्य ओदनस्य अङ्गानि घृतेन क्षरणशीलेन आज्येन अनु वि मृड्ढि आनुपूर्व्येण विमार्जय । स्वभ्यक्तानि कुर्वित्यर्थः । अनेन ओदनेन पन्थाम् पन्थानं मार्गं कृण्वे कुर्वे । कीदृशः स पन्था इत्याह पितृष्विति । पितृषु पितृपितामहादिषु पूर्वपुरुषेषु विषयभूतेषु यः पन्थाः स्वर्गः स्वर्लोकं प्रति ऋजुत्वेन गच्छति [तथाविधः] । ⧖ स्वर्शब्दोपपदाद् "गमेर्डोन्यत्रापि दृश्यते" इति डप्रत्ययः ⧖ । स्वर्गप्राप्तिसाधनभूतो मार्ग इत्यर्थः ॥

---

१ B कृणोहि. We with A C D E V K K[m] B[h] R S[m] Cs.

द्वितीया ॥

बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥ ३२ ॥

बभ्रे । रक्षः । सऽमदम् । आ । वप । एभ्यः । अब्राह्मणाः । यतमे । त्वा ।
उपऽसीदान् ।
पुरीषिणः । प्रथमानाः । पुरस्तात् । आर्षेयाः । ते । मा । रिषन् । प्रऽअ-
शितारः ॥ ३२ ॥

हे बभ्रे भरणशील ब्रह्मौदन अब्राह्मणाः ब्राह्मणव्यतिरिक्ताः क्षत्रियाद्या यतमे ये त्वा त्वाम् उपसीदान् उपसीदेयुः प्राशनार्थम् उपसन्ना भवेयुः । "वा बहूनां जातिपरिप्रश्ने°" इति यच्छब्दात् डतमच् । तदन्तस्य सर्वनामसंज्ञायां जसः शीभावः । एभ्यः ब्राह्मणव्यतिरिक्तेभ्यः रक्षःसमदम् रक्षोजात्या सह मदनम् । यद्वा समानं माद्यन्ति अस्मिन्निति समत् संग्रामः राक्षसैः कलहम् आ वप प्रक्षिप । राक्षसकृतां पीडां प्रापयेत्यर्थः । ये तु पुरस्ताद् उक्ता आर्षेयाः ऋषिगोत्रप्रवराभिज्ञाः पुरीषिणः पृणाति पूरयतीति वा पुरीषं प्रजापश्वादिकम् । श्रूयते हि । "प्रजा वै पशवः पुरीषम् । प्रजयैवैनं पशुभिः पुरीषवन्तं करोति" इति [तै° सं° २, ६, ४, ३] । यास्कस्तु पुरीषशब्दं निरवोचत् । पुरीषं पृणातेः पूरयतेर्वेति [नि° २, २२] । तद् एषाम् अस्तीति पुरीषिणः । अत एव प्रथमानाः लोके पुत्रपौत्रादिसमृद्ध्या विस्तीर्यमाणास्ते* भृग्वङ्गिरोविदो ब्राह्मणाः हे ओदन तव प्राशितारः भोक्तारः मा रिषन् हिंसां मा प्राप्नुवन्तु । रिष हिंसायाम् । समृद्धा भवन्तु इत्यर्थः ॥

तृतीया ॥

आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।
अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥ ३३ ॥

---

१ P बभ्रे. CP बभ्रे changed to बभ्रे. We with P² J.

आर्षेयेषु । नि । दधे । ओदन । त्वा । न । अनार्षेयाणाम् । अपि । अ-
स्ति । अत्र ।

अग्निः । मे । गोप्ता । मरुतः । च । सर्वे । विश्वे । देवाः । अभि । रक्षन्तु ।
पक्वम् ॥ ३३ ॥

हे ओदन त्वा त्वाम् आर्षेयेषु प्रागुक्तलक्षणेषु ब्राह्मणेषु नि दधे नितरां स्थापयामि । अत्र अस्मिन् ब्रह्मौदने अनार्षेयाणाम् ऋषिगोत्रप्रवरानभिज्ञानां पुरुषाणाम् । ⌛अपिः संभावनार्थः⌛ । संभावनापि नैवास्ति विद्यते । मे मम अग्निः अग्रणीर्देवो गोप्ता गोपायिता रक्षिता । ⌛गुपू रक्षणे । तृचि "आयादय आर्धधातुके वा" इति आयप्रत्ययाभावः⌛ । तथा सर्वे सप्तगणात्मका [मरुतः] मरुत्संज्ञा देवाश्च । मम गोप्तार इति विपरिणामेन संबन्धः । अपि च विश्वे सर्वे देवाः मित्रवरुणार्यमादयः पक्वम् पाकेन संस्कृतम् इमं ब्रह्मौदनम् अभि रक्षन्तु अभितः पालयन्तु । ⌛पक्वम् इति । पचेः कर्मणि निष्ठा । "पचो वः" इति निष्ठातकारस्य वकारः⌛ ॥

चतुर्थी ॥

यज्ञं दुहानं सदमित् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥ ३४ ॥

यज्ञम् । दुहानम् । सदम् । इत् । प्रऽपीनम् । पुमांसम् । धेनुम् । सद-
नम् । रयीणाम् ।

प्रजाऽअमृतत्वम् । उत । दीर्घम् । आयुः । रायः । च । पोषैः । उप ।
त्वा । सदेम ॥ ३४ ॥

यज्ञम् अग्निहोत्रदर्शपूर्णमासाद्यात्मकं दुहानम् उत्पादयन्तम् । ब्रह्मौदनपाकानन्तरमेव हि आधानादिवैतानक्रियास्वधिकार इति ब्रह्मौदनस्य कारणत्वोपन्यासः । सदम् इत् सदैव प्रपीनम् प्रवृद्धोधस्कम् । ⌛प्यायी वृद्धौ । अस्मात् प्रपूर्वात् निष्ठायां "प्यायः पी" इति पी आदेशः⌛ । पुमांसं धेनुम् । उक्तलक्षणो ब्रह्मौदनः पुंरूपा धेनुरित्य-

र्थः । तथा रयीणाम् धनानां सदनम् उपवेशनस्थानम् । "अन्नाद् भूतानि जायन्ते" [तै० आ० ८.२] इत्यादिश्रुतेः । हे ओदन एवंभूतं त्वा त्वां भुञ्जाना वयं प्रजाऽमृतत्वम् प्रकर्षेण जायत इति प्रजा पुत्रपौत्रादिरूपा तया यत् अमृतत्वम् अमरणधर्मता । सांतत्येन वृत्तिरित्यर्थः । श्रूयते हि । "प्रजाम् अनु प्रजायसे । तदु ते मर्त्यामृतम्" इति [तै० ब्रा० १.५.५.६] "प्रजाभिरग्ने अमृतत्वम् अश्याम्" इति [ऋ० सं० ५.४.१०] च । [ताम्] उत अपि च दीर्घम् शतसंवत्सरपरिमितम् आयुः जीवनम् । तथा रायः धनस्य पोषैः समृद्धिभिश्च सह प्रजाऽमृतत्वादिकं सर्वं फलम् उप सदेम उपगम्यास्म । यद्वा प्रजाऽमृतत्वादिरूपं त्वाम् इति सामानाधिकरण्येन संबन्धः । सदेः आशीर्लिङि "लिङ्याशिष्यङ्" इति अङ् प्रत्ययः ॥

पञ्चमी ॥

वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ ।
सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥ ३५ ॥

वृषभः । असि । स्वःऽगः । ऋषीन् । आर्षेयान् । गच्छ ।
सुऽकृताम् । लोके । सीद । तत्र । नौ । संस्कृतम् ॥ ३५ ॥

हे ब्रह्मौदन त्वं [वृषभः] कामानां वर्षिता असि भवसि । तथा स्वर्गः स्वर्लोकस्य गन्ता गमयिता वा भवसि । अतः ऋषीन् मन्त्रद्रष्टॄन् आर्षेयान् उदीरितलक्षणान् ब्राह्मणान् गच्छ अस्माभिर्दीयमानः प्राप्नुहि । तैरुपभुक्तः सन् पश्चाद् अदृष्टरूपेण सुकृताम् पुण्यकृतां फलभूते लोके नाकपृष्ठाख्ये सीद उपविश । ततः परं नौ आवयोस्तत्र खलु सुकृतफलभूते लोके संस्कृतम् संस्कारो भोक्तृभोक्तव्यात्मकः । संपत्स्यत इत्यर्थः ॥

षष्ठी ॥

समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।

१ B °याह्यग्ने. We with A B^h C D E K K^m R S^m P P^2 J V Cs, though they read the accent wrongly.

1 S′ तदू.

एतैः सुकृतैरनु गच्छेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥ ३६ ॥

सम्ऽआचिनुष्व । अनुऽसंप्रयाहि । अग्ने । पथः । कल्पय । देवऽयानान् । एतैः । सुऽकृतैः । अनु । गच्छेम । यज्ञम् । नाके । तिष्ठन्तम् । अधि । सप्तऽरश्मौ ॥ ३६ ॥

हे ओदन त्वं समाचिनुष्व समाचयनम् सर्वेषाम् अङ्गानां समूहीभवनं कुरु । अनु पश्चात् संप्रयाहि गन्तव्यान् प्रति गच्छ । हे अग्ने त्वमपि अस्य ओदनस्य गमनाय देवयानान् पथः देवा एव यैर्यान्ति गच्छन्ति तादृशान् मार्गान् कल्पय विरचय । वयमपि एतैरेव देवयानैः पथिभिः सुकृतैः पुण्यफलभूतैः नाके दुःखासंसृष्टे स्वर्गे लोके अधि सप्तरश्मौ आदित्यमण्डलस्योपरि तिष्ठन्तं यज्ञम् अनु गच्छेम अनुप्राप्नुयाम । स्मर्यते हि । "अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते" इति [म° स्मृ° ३.७६] ॥

सप्तमी ॥

येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥ ३७ ॥ (४)

येन । देवाः । ज्योतिषा । द्याम् । उत्ऽआयन् । ब्रह्मऽओदनम् । पक्त्वा । सुऽकृतस्य । लोकम् ।
तेन । गेष्म । सुऽकृतस्य । लोकम् । स्वः । आऽरोहन्तः । अभि । नाकम् । उत्ऽतमम् ॥ ३७ ॥ (४)

देवा इन्द्रादयो येन ज्योतिषा सूर्यरश्मिलक्षणेन तेजसा । "अग्निर्ज्योतिरहः शुक्लः" [भ° गी° ८.२४] इत्युदीरितलक्षणस्य देवयानमार्गस्य उपलक्षणम् एतत् । येन[1] पथा द्याम् द्युलोकं स्वर्गम् उदायन् उदगच्छन् । किं कृत्वेत्याह । ब्रह्मौदनं पक्त्वा । एतद् ब्रह्मौदनसवाख्यं कर्म अनुष्ठाये-

१ So P P² J. Cp अग्ने corrected to अग्ने probably intended to be अग्ने.

1 S' तेन.

त्यर्थः । द्यां विशिनष्टि । सुकृतस्य पुण्यकर्मणः फलभूतं लोकम् । यतो देवा अनेन पथा उदायन् ततो हेतोः अस्य मार्गस्य देवयानसंज्ञा निष्पन्नेति भावः । तेन देवयानेन पथा वयमपि सुकृतस्य सुकर्मणः सवयज्ञात्मकस्य फलभूतं लोकं *जेष्म जयेम प्राप्नुयाम । उक्त एवार्थो विव्रियते । उत्तमम् उत्कृष्टतमं नाकम् नाकपृष्ठाख्यं स्थानविशेषम् अभिलक्ष्य स्वः आरोहन्तः । तदुपायत्वेन स्वर्गाख्यं स्थानं प्रथमम् अधिरोहन्त इत्यर्थः । यद्वा । "लक्षणहेत्वोः क्रियायाः" इति हेतौ शतृप्रत्ययः । स्वर्गारोहणाद्धेतोः सुकृतफलं प्रथमं जयेमेति पूर्वत्र संबन्धः ॥

एवम् "अग्ने जायस्व" इत्यादिसूक्तचतुष्टयं ब्रह्मौदनाख्यस्य साङ्गस्य[1] कर्मणः प्रतिपादकत्वेन अर्थत एकत्वाद् अर्थसूक्तम् इति मन्त्रद्रष्टृभिः परिभाष्यते । एवं सर्वेष्वर्थसूक्तेषु द्रष्टव्यम् ॥

[इति] एकादशकाण्डे प्रथमेनुवाके चतुर्थं सूक्तम् ॥

"भवाशर्वौ मृडतम्" इत्यादिसूक्तत्रयम् अर्थसूक्तम् । तेन अर्थसूक्तेन स्वस्त्ययनकामः आज्यसमित्पुरोडाशादिशष्कुल्यन्तानां त्रयोदशद्रव्याणाम् अन्यतमं जुहुयात् । सर्वाणि वा त्रयोदश द्रव्याणि जुहुयात् । सूत्रितं हि । "विश्वजित्[६.१०७] शकधूमम्[६.१२८] भवाशर्वौ[११.२] इत्युपदधीत" इति [कौ० ७.१] ॥

तथा रुद्रभूतप्रेतराक्षसलोकपालादिनिमित्ताभिघाते स्वस्त्ययनार्थं सरूपवत्साया गोर्दुग्धे पक्वं चरुं त्रिधा विभज्य समस्तेन अर्थसूक्तेन रुद्रदेवतायै तिस्र आहुतीर्जुहुयात् । सूत्रितं हि । "विश्वजित्[६.१०७] शक-
"धूमम्[६.१२८] भवाशर्वौ[११.२] इत्युपदधीत । उत्तमेन सारूप-
"वत्सस्य रुद्राय त्रिर्जुहोति" इति [कौ० ७.१] ॥

तथा मांसमुखाग्रपतनलक्षणाद्भुतशान्त्यर्थम् अनेन अर्थसूक्तेन रुद्राय आज्यं जुहुयात् । "अथ यत्रैतन्मांसमुखो निपतति तत्र जुहुयात्" इति प्रक्रम्य कौशिकेन सूत्रितम् । "रुद्राय स्वाहेति हुत्वा भवाशर्वौ मृडतं माभि यातम् इत्येतेन सूक्तेन जुहुयात् । सा तत्र प्रायश्चित्तिः" इति [कौ० १३.३७] ॥

1 S' सांगकस्य.

तथा अग्निचयने रौद्रीरिष्टका अनेनार्थसूक्तेन अनुमन्त्रयेत । तद् उक्तं वैताने । "भवाशर्वौ मृडतम्[११.२] यस्ते सर्पः[१२.१.४६] इति रौद्रीः[1]" इति [वै° ५.२] ॥

तथा सर्वकामप्राप्त्यर्थं शान्त्यर्थं वा क्रियमाणे लक्षहोमे एतद् अर्थसूक्तम् । तथा च आथर्वणपरिशिष्टेभिहितम् । " 'ब्रजश्च मे क्षत्रं च मे' "ये अग्नयः[३.२१] नमो देववधेभ्यः[६.१३] भवाशर्वौ[११.२] "प्राणाय नमः[११.६] इति हुत्वा" इति ॥

तत्र प्रथमा ॥

भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥ १ ॥

भवाशर्वौ । मृडतम् । मा । अभि । यातम् । भूतपती इति भूतऽपती । पशुपती इति पशुऽपती । नमः । वाम् ।
प्रतिऽहिताम् । आऽयताम् । मा । वि । स्राष्टम् । मा । नः । हिंसिष्टम् । द्विऽपदः । मा । चतुःऽपदः ॥ १ ॥

एतदादिसूक्तत्रयेण भौमान्तरिक्षाद्युत्पातदोषनिवृत्तये अष्टमूर्तिर्महादेवः प्रार्थ्यते । ताश्च पारमेश्वर्यो मूर्तयः आगमिकैरेवम् अनुक्रान्ताः ।

शर्वं पशुपतिं चोग्रं रुद्रं भवम् अथेश्वरम् ।
महादेवं च भीमं च ।

इति । तासाम् उत्पत्तिः शतपथब्राह्मणे षष्ठकाण्डे "असद् वा इदम् अग्र आसीत्" [श° ब्रा° ६.१.१.१] इत्यादिना प्रपञ्चिता । तत्र सृष्ट्यादौ भवति यस्मात् सर्वं जगद् इति भवः । शृणाति सर्वं जगद्धिनस्ति संहृतिसमये इति शर्वः । स्थितिकालवर्तिनीनाम् अन्यासा मूर्तीनाम् उपसंग्रहाय सृष्टिसंहृतिकारिण्यौ आद्यन्तवर्तिन्यौ परमेश्वरस्य मूर्ती निर्दिश्येते । भवश्च

1 So S′. The *Vaitâna* (ed. Garbe 1878, and our own MSS. of the text) reads रौद्रान्. Somâditya's *Âkshepa*, a commentary on the *Vaitâna*, also reads रौद्रान् and explains it by होमान्.

शर्वश्च भवाशर्वौ । "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ् आदेशः । हे भवाशर्वौ एतत्संज्ञौ देवौ मृळतम् अस्मान् सुखयतम् । मृड सुखने । तथा मा माम् अभि यातम् रक्षणार्थम् आभिमुख्येन गच्छतम् । यद्वा हिंसार्थम् अभिगमनं मा कार्ष्टम् । हे भूतपती भूतानां प्राणिनां स्वामिनौ हे पशुपती पशूनां गोमहिषादीनां पालयितारौ वाम् युवाभ्यां नमः । करोमीति शेषः । अस्मदीयेन नमस्कारेण संतुष्टौ युवां प्रतिहिताम् आत्मीये धनुषि प्रतिसंहिताम् आयताम् ज्यया सह आकृष्टाम् आत्मीयाम्[1] इषुं मा वि स्राष्टम् अस्मदाभिमुख्येन मा विसृजतम् । "याम् इषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे" इति हि निगमः [तै॰ सं॰ ४. ५. १. २] । सृज विसर्गे इत्यस्माद्धातोर्माङि लुङि मध्यमद्विवचने "सृजिदृशोर्झल्यम् अकिति" इति अम् आगमः । "सिचि वृद्धिः परस्मैपदेषु" इति वृद्धिः । "झलो झलि" इति सलोपः । "व्रश्च॰"इत्यादिषत्वे ष्टुत्वम् । तथा[2] नः अस्माकं द्विपदः पादद्वयोपेतान् पुत्रभृत्यादिरूपान् मनुष्यान् मा हिंसिष्टम् । ज्वरादिरोगेण पीडितान् मा कार्ष्टम् इत्यर्थः । तथा चतुष्पदः पादचतुष्टयोपेतान् गोमहिषाश्वादीन् अस्मदीयान् मा हिंसिष्टम् । द्वौ पादावस्य चत्वारः पादा अस्येति विगृह्य समासे "संख्यासुपूर्वस्य" इति पादशब्दस्य अन्त्यलोपः । शसि भसंज्ञायां "पादः पत्" इति पद्भावः । द्विपद इत्यत्र "द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ" इति उत्तरपदान्तोदात्तत्वम् । चतुष्पद इत्यत्र तु "बहुव्रीहौ प्रकृत्या॰" इति पूर्वपदप्रकृतिस्वरत्वम् ॥

द्वितीया ॥

शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑[१]म॒लिक्ल॑वे[२]भ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑ ।
मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥ २ ॥

---

१ V K कर्तु॑म॒॰. We with A B B[h] C D E V K[m] R S[m] P P[2] J Cs, though wrong in the accent. २ V ॰म॒लिक्ल॑वेभ्यो॒. We with A B B[h] C D E K K[m] R S[m] P P[2] J Cs.

---

1 S′ omits ॰म् इषुं. 2 S′ inserts च after तथा.

शुने॑ । क्रो॒ष्ट्रे । मा । शरी॑राणि । कर्त॑म् । अ॒लिक्ल॑वेभ्यः । गृध्रे॑भ्यः । ये । च॒ ।
कृ॒ष्णाः । अ॒वि॒ष्यवः॑ ।

मक्षि॑काः । ते॒ । प॒शु॒ऽप॒ते॒ । वयां॑सि । ते॒ । वि॒ऽघ॒से । मा । वि॒द॒न्त॒ ॥ २ ॥

हे भवाशर्वौ शरीराणि अस्मत्संबन्धीनि शुने सारमेयाय । "श्वयुवमघोनाम् अतद्धिते" इति संप्रसारणम् । क्रोष्ट्रे सृगालाय । "विभाषा तृतीयादिष्वचि" इति क्रोष्टृशब्दस्य तृज्वद्भावः । उभयत्र तादर्थ्ये चतुर्थी । श्वसृगालभक्षणार्थं कर्तुं मा । प्रभवतम् इत्यर्थः । तथा अविक्लवेभ्यः विक्लवा अधृष्टाः कातरास्तद्विपरीतेभ्यः । वर्णविकारश्छान्दसः । गृध्रेभ्यः मांसमुखेभ्यः पक्षिभ्यः । ये च कृष्णाः कृष्णवर्णा वायसाः अविष्यवः आमिषम् इच्छन्तः अन्तरिक्षे संचरन्ति तेभ्यश्च । गृध्रकाकादिपक्षिणां भक्षणार्थमपि अस्मच्छरीराणि मा कुरुतम् इत्यर्थः । हे पशुपते पशूनाम् अधिपते रुद्र ते त्वदीया मक्षिकाः तथा ते त्वदीयानि वयांसि पक्षिणश्च विघसे विशेषेण अद्यत इति विघसः अन्नम् । "उपसर्गेऽदः" इति अप् । "घञपोश्च" इति घस्लृ आदेशः । तस्मिन् विघसे अन्ने निमित्तभूते सति मा विदन्त अस्मच्छरीराणि न लभन्ताम् । मा भक्षयन्तु इत्यर्थः । विद्लृ लाभे । माङि लुङि लृदित्वात् च्लेः अङ् आदेशः ॥

तृतीया ॥

क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः ।
नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥ ३ ॥

क्रन्दा॑य । ते॒ । प्रा॒णाय॑ । याः । च॒ । ते॒ । भ॒व॒ । रोप॑यः ।

१ So P P[2] J Cp distinctly. Sâyaṇa: कर्तुम्, which is not so good as कर्तम्. (Sâyaṇa's text too is: कर्तुम्). But then कर्तम् ought to be क॒र्त॒म्. Perhaps it was this difficulty that determined Sâyaṇa in favour of कर्तुम्. Wrongly accented as it is we prefer कर्तम्. २ So P P[2] J Cp. ३ P P[2] J Cp अ॒वि॒द॒न्त॒. We with Sâyaṇa.

1 There is much stretching here. Sâyaṇa did not know that the easier reading कर्तम् did exist.

नमः । ते । रुद्र । कृण्मः । सहस्रऽअक्षाय । अमर्त्य ॥ ३ ॥

हे भव ते तव क्रन्दाय क्रन्दनाय शब्दाय प्राणाय प्राणवायवे नमस्कुर्मः । यद्वा क्रन्दयति रोदयति सर्वम् अन्तकाले इति क्रन्दः । क्रदि क्रदि क्लदि आह्वाने रोदने च । तथा प्राणाय प्राणयित्रे प्राणनव्यापारेण चेष्टयित्रे जगत्प्राणभूताय वा ते तुभ्यं नमस्कुर्मः । तथा हे भव ते तव याश्च रोपयः रोपयित्र्यो मोहयित्र्यस्तन्वः सन्ति ताभ्यश्च नमस्कुर्म इत्यर्थः । युप रुप लुप विमोहने । अस्माद् औणादिक इकारप्रत्ययः ॥ हे रुद्र । रोदयति सर्वम् अन्तकाल इति रुद्रः । रोदेर्णिलुक् च इति [उ० २, २२] रक् प्रत्ययः । णिचो लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् लघूपधगुणाभावः । यद्वा रुद् दुःखं दुःखहेतुर्वा तस्य द्रावको देवो रुद्रः परमेश्वरः । हे देव सहस्राक्षाय सहस्रम् अक्षीणि दर्शनशक्तयो यस्य स तथोक्तः । सर्वजगत्साक्षिणे । निरावरणज्ञानरूपायेत्यर्थः । "बहुव्रीहौ सक्थ्यक्ष्णोः०" इति षच् समासान्तः । अमर्त्यः । "सुपां सुलुक्०" इति चतुर्थ्येकवचनस्य सु आदेशः । अमर्त्याय अमरणधर्मणे । सांसारिकदुःखासंस्पृष्टायेत्यर्थः । एवंभूताय ते तुभ्यं नमः नमस्कारं कृण्मः कुर्मः ॥

चतुर्थी ॥

पुरस्तात् ते नमः कृण्म उत्तरादधरादुत ।
अभीवर्गाद् दिवस्पर्यन्तरिक्षाय ते नमः ॥ ४ ॥

पुरस्तात् । ते । नमः । कृण्मः । उत्तरात् । अधरात् । उत ।
अभिऽवर्गात् । दिवः । परि । अन्तरिक्षाय । ते । नमः ॥ ४ ॥

हे रुद्र ते तुभ्यं पुरस्तात् पूर्वस्यां दिशि नमः कृण्मः नमस्कारं कुर्मः । तथा उत्तरात् उत्तरस्यां दिशि । अधरात् । अधरशब्दो दक्षिणदिग्वचनः । "पश्चात् पुरस्ताद् अधराद् उदक्तात्" [ऋ० १०, ८७, २१] इत्यादिनिगमेषु तथा दर्शनात् । अधरस्यां दक्षिणस्यां दिशि । "उ-

त्तराधरदक्षिणाद् आतिः" इति सप्तम्यर्थे आतिप्रत्ययः । उतश-ब्दः अप्यर्थे । दक्षिणोत्तरदिशोरवस्थिताय ते तुभ्यं नमः । कृण्म इ-त्यनुषङ्गः । अभीवर्गात् अभितो वृज्यते गृहादिरूपेण परिच्छिद्यते इति अभीवर्गः अवकाशात्मक आकाशः । वृजी वर्जने । कर्मणि घञ् । "उपसर्गस्य घञ्यमनुष्ये बहुलम्" इति दीर्घः । तादृशाद् दिवः द्योतमानाद् आकाशात् परि उपरिभागे । "पञ्चम्यपाङ्परि-भिः" इति पञ्चमी । "पञ्चम्याः परावध्यर्थे" इति विसर्जनीयस्य स-त्वम् । आकाशमण्डलस्य मध्ये अन्तरिक्षाय अन्तरा क्षान्ताय नि-यन्तृत्वेन अवस्थिताय ते तुभ्यं नमस्कुर्मः । "अस्मिन् महत्यर्णवेन्तरिक्षे भवा अधि" इति हि निगमान्तरम् [तै॰ सं॰ ४. ५. ११. १] ॥

पञ्चमी ॥

मुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव ।
त्व॒चे रू॒पाय॑ सं॒दृशे॑ प्र॒तीचीना॑य ते॒ नमः॑ ॥ ५ ॥
मुखा॑य । ते॒ । प॒शु॒ऽप॒ते॒ । यानि॑ । चक्षूं॑षि । ते॒ । भ॒व॒ ।
त्व॒चे । रू॒पाय॑ । स॒म्ऽदृशे॑ । प्र॒ती॒चीना॑य । ते॒ । नमः॑ ॥ ५ ॥

हे पशुपते पशूनां पालयितर्देव ते त्वदीयाय मुखाय आस्याय नमो-स्तु । हे भव एतत्संज्ञक देव ते तव यानि चक्षूंषि दर्शनसाधनानि इ-न्द्रियाणि सन्ति तेभ्यो नमोस्तु । तथा त्वचे त्वच्छरीरसंबन्धिने चर्मणे रूपाय नीलपीतादिवर्णाय संदृशे सम्यग्दर्शनाय । यद्वा सम्यग् अर्थान् पश्यतीति संदृक् संद्रष्टा तद्रूपाय । प्रतीचीनाय प्रत्यगात्मरूपिणे ते तुभ्यं नमोस्तु । प्रतिपूर्वाद् अञ्चतेः "ऋत्विग्॰" इत्यादिना क्विन् । "अनिदिताम्॰" इति नलोपः ॥ "विभाषाञ्चेरदिक्स्त्रियाम्" इति स्वा-र्थिकः खप्रत्ययः ॥

षष्ठी ॥

अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वायां॑ आ॒स्या॑य ते ।
द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥ ६ ॥

अङ्गेभ्यः । ते । उदराय । जिह्वायै । आस्याय । ते ।
दत्ऽभ्यः । गन्धाय । ते । नमः ॥ ६ ॥

हे पशुपते ते तव संबन्धिभ्यः अङ्गेभ्यः हस्तपादादिभ्यो नमोस्तु । सामान्योक्तमेव प्राधान्यख्यापनाय विशेषतो निर्दिशति । ते तव लीलाविग्रहधारिणः संबन्धिने उदराय जिह्वायै रसनायै [आस्याय] आस्याख्यकुहराय दद्भ्यः दन्तेभ्यः गन्धाय गन्धग्राहकेन्द्रियाय घ्राणाय ते त्वत्संबन्धिने नमः । दद्भ्य इति । "पद्दन्°" इत्यादिना दन्तशब्दस्य दद्भावः ॥

सप्तमी ॥

अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।
रुद्रेणार्धकघातिना तेन मा समरामहि ॥ ७ ॥

अस्त्रा । नीलऽशिखण्डेन । सहस्रऽअक्षेण । वाजिना ।
रुद्रेण । अर्धकऽघातिना । तेन । मा । सम् । अरामहि ॥ ७ ॥

अस्त्रा क्षेप्त्रा नीलशिखण्डेन नीलवर्णकेशसंनिवेशविशेषयुक्तेन सहस्राक्षेण सहस्रसंख्याकचक्षुरिन्द्रिययुक्तेन वाजिना वेगवता अर्धकघातिना सेनाया अर्धं हन्तुं शीलम् अस्य । "सुप्यजातौ णिनिस्ताच्छील्ये" इति हन्तेर्णिनिप्रत्ययः । "हनस्तोचिण्णलोः" इति तत्वम् । "हो हन्तेर्ञ्णिन्नेषु" इति घत्वम् । एवंगुणविशिष्टेन तेन प्रसिद्धेन रुद्रेण मा सम् अरामहि मा संगच्छामहै । आर्ता मा भूमेत्यर्थः । ऋ गतौ । अस्मात् माङि लुङि "समो गम्यृच्छि°" इति आत्मनेपदम् । "सर्तिशास्त्यर्तिभ्यश्च" इति च्लेः अङ् आदेशः ॥

अष्टमी ॥

स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।
मा नोभि मांस्त नमो अस्त्वस्मै ॥ ८ ॥

---

१ P आस्याय. We with P J K Cp. २ P मा. We with P J Cp. ३ B मांस्त.

सः। न॒ः। भ॒वः। परि॑। वृ॒ण॒क्तु॒। वि॒श्वत॑ः। आप॑ःऽइव। अ॒ग्निः। परि॑।
वृ॒ण॒क्तु॒। न॒ः। भ॒वः।
मा। न॒ः। अ॒भि। मा॒ंस्त॒। नम॑ः। अ॒स्तु॒। अ॒स्मै॒॥ ८॥

सः उदीरितप्रभावो भवः नः अस्मान् विश्वतः विश्वस्मात् सर्वस्माद् उपद्रवजातात् परि वृणक्तु परितो वर्जयतु। अयमेवार्थो दृष्टान्तेन दृढीक्रियते आप इवाग्निरिति। यथा दहन्नग्निः आपः। ⧗शसि छान्दसी वृद्धिः⧗। अपः उदकानि परिवर्जयति परित्यजति एवं नः अस्मान् भवः परि वृणक्तु परित्यजतु। नः अस्मान् [माभि मंस्त*1] मा अभिमन्यताम्। मा बाधताम् इत्यर्थः। ⧗अभिपूर्वो मन्यतिर्हिंसने वर्तते। अस्मान्माङि लुङि "एकाच उपदेशेनुदात्तात्" इति सिच इट्प्रतिषेधः। "न माङ्योगे" इति अडभावः⧗। अस्मै भवाय नमोस्तु नमस्कारो भवतु॥

नवमी॥

च॒तुर्नमो॑ अष्टकृ॒त्वो॑ भ॒वाय॒ दश॒ कृत्व॑ः पशुपते॒ नम॑स्ते।
तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वा॑ः पुरु॑षा अजा॒वय॑ः॥ ९॥

च॒तुः। नम॑ः। अ॒ष्ट॒ऽकृ॒त्व॑ः[१]। भ॒वाय॑। दश॑। कृत्व॑ः। प॒शु॒ऽप॒ते॒। नम॑ः। ते॒।
तव॑। इ॒मे। पञ्च॑। प॒शव॑ः। विऽभ॑क्ताः। गाव॑ः। अश्वा॑ः। पुरु॑षाः। अ॒ज॒ऽअ॒वय॑ः॥ ९॥

अष्टकृत्वो भवायेति विशेषणात् चतुर्नम इत्यत्र शर्वायेति अर्थात् संबध्यते। चतुः चतुर्वारं शर्वाय नमोस्तु। ⧗"द्वित्रिचतुर्भ्यः सुच्" इति क्रियाभ्यावृत्तिगणने सुच् प्रत्ययः⧗। तथा भवाय देवाय अष्टकृत्वः अष्टवारं नमोस्तु। ⧗"संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" इति कृत्वसुच् प्रत्ययः⧗। हे पशुपते ते तुभ्यं दश*कृत्वः दशवारं नमोस्तु। कस्माद् एवं प्रार्थ्यस इत्युच्यते। इमे वक्ष्यमाणा वि-

१ P² °कृत्वां. We with P J Cp.

1 Sâyaṇa's text too reads मंस्त, not मांस्त.

भक्ताः जातितो भिन्नाः हे पशुपते तव स्वभूताः गावः गोत्वजातीयाः सास्नादिमद्व्यक्तयः अश्वाः अश्वजात्याक्रान्ता एकखुराः पशवः पुरुषाः मनुष्यजातीयाः अजाश्च अवयश्च अजावयः । अजत्वावित्वे द्वे जाती विभिन्नव्यक्तिके प्रसिद्धे । यस्माद् इमे पञ्चधा भिन्नाः पशवस्तव स्वभूतास्तस्मात् तान् रक्षेति प्रार्थ्यस इत्यर्थः ॥

दशमी ॥

तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॑१न्तरि॑क्षम् ।
तवे॒दं सर्व॑मात्म॒न्वद् यत् प्रा॒णत् पृ॑थि॒वीमनु॑ ॥ १० ॥ (५)

तव॑ । चत॑स्रः । प्र॒ऽदिशः॑ । तव॑ । द्यौः । तव॑ । पृ॒थि॒वी । तव॑ । इ॒दम् । उ॒ग्र॒ । उ॒रु । अ॒न्तरि॑क्षम् ।

तव॑ । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । पृ॒थि॒वीम् । अनु॑ ॥ १० ॥ (५)

हे उग्र उद्गूर्णबल रुद्र चतस्रः चतुःसंख्याकाः प्रदिशः प्रधानभूताः प्राच्याद्या महादिशस्तव स्वभूताः । तथा द्यौः स्वर्गलोकोपि तव वशे वर्तते । पृथिवी भूलोकश्च तव स्वभूता । इदं परिदृश्यमानम् उरु विस्तीर्णम् अन्तरिक्षं च तवाधीनम् । इत्थं दिग्वलयं लोकत्रयं च व्याप्य अवस्थितस्य तव इदं परिदृश्यमानं सर्वम् आत्मन्वत् आत्मना भोक्तृरूपेण अधिष्ठितं शरीरजातं स्वभूतम् । आत्मा अस्यास्तीति आत्मन्वत् । मतुपि पदसंज्ञायां नलोपे "मादुपधायाः०" इति वत्वम् । "अनो नुट्" इति नुडागमः । तथा पृथिवीम् अनु । लक्षणे अनोः कर्मप्रवचनीयत्वम् । पृथिवीं लक्षीकृत्य । पृथिव्याम् इत्यर्थः । यत् प्राणत् प्राणनव्यापारं कुर्वद् वर्तते तत् सर्वं तव । प्रशासने वर्तत इत्यर्थः । तस्मात् सर्वेषाम् अनुग्रहाय त्वमेव नमस्कार्यो भवसीति भावः ॥

[इति] पञ्चमं सूक्तम् ॥

"उरुः कोशः" इत्यस्य सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ॥

तत्र प्रथमा ॥

उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः ।

स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्व-
घरुदो विकेश्यः ॥ ११ ॥

उरुः । कोशः । वसुऽधानः । तव । अयम् । यस्मिन् । इमा । विश्वा । भुवनानि । अन्तः ।

सः । नः । मृड । पशुऽपते । नमः । ते । परः । क्रोष्टारः । अभिऽभाः । श्वानः । परः । यन्तु । अघऽरुदः । विऽकेश्यः ॥ ११ ॥

हे पशुपते पशूनां पालयितर्महादेव उरुः विस्तीर्णो वसुधानः वसूनि वासहेतुभूतानि पुण्यपापरूपाणि कर्माणि धीयन्ते अस्मिन्निति वसुधानः । ※दधातेः अधिकरणे ल्युट्※ । एवंभूतः कोशः अण्डकटाहात्मकः तवायम् । तव स्वभूतोयम् इत्यर्थः । कोशं विशिनष्टि । यस्मिन् अण्डकटाहात्मके महति कोशे अन्तः मध्ये इमा इमानि परिदृश्यमानानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि वर्तन्ते । स कोशस्तव स्वभूत इति संबन्धः । स तथाविधस्त्वं नः अस्मान् मृड सुखय । ते तुभ्यं नमोस्तु । त्वत्प्रसादात् अभिभाः अभिभवितारः क्रोष्टारः क्रोशनशीलाः सृगाला मांसभक्षकाः श्वानश्च परः परस्तात् अस्मत्तो दूरदेशे यन्तु गच्छन्तु । तथा अघरुदः अघम् अमङ्गलं यथा भवति तथा रुदत्यः रोदनं कुर्वत्यः विकेश्यः विकीर्णकेशाः पिशाच्यश्च परो यन्तु परस्ताद् दूरं गच्छन्तु ॥

द्वितीया ॥

धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्नि[1] शतवधं शिखण्डिन्[2] ।
रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशी३तः[3] ॥ १२ ॥

धनुः । बिभर्षि । हरितम् । हिरण्ययम् । सहस्रऽघ्नि[4] । शतऽवधम् । शिखण्डिन् ।

---

१ B^h C R K^m सहस्रघ्निं. V K सहस्रघ्यं. We with A D E S^m P P^2 J Cs. २ B शिखण्डिनम्. We with A B^h C D E K K^m R S^m P P^2 J V Cs. ३ K १ for ३. We with A B B^h C D E K^m R S^m V Cs. ४ So P P^2 J. Cp सहस्रऽघ्निं.

रुद्रस्य । इषुः । चरति । देवऽहेतिः । तस्यै । नमः । यतमस्याम् । दिशि । इतः ॥ १२ ॥

हे रुद्र त्वं संहृतिसमये विश्वसंहरणार्थं धनुर्बिभर्षि धारयसि । डुभृञ् धारणपोषणयोः । जुहोत्यादित्वात् शपः श्लुः । "भृञाम् इत्" इति अभ्यासस्य इत्त्वम् । कीदृशं तद्धनुरिति विशिनष्टि । हरितम् हरिद्वर्णं हिरण्ययम् हिरण्यविकारम् । स्वर्णमयम् इत्यर्थः । "ऋत्व्य-[वास्त्व्य]वास्त्वमाध्वीहिरण्ययानि च्छन्दसि" इति हिरण्यशब्दात् मतुपि वर्णलोपो निपात्यते[1] । सहस्रघ्नम्[*] सहस्रसंख्याकान् एकयत्नेन हन्ति हिनस्तीति सहस्रघ्नम्[2] । वर्णोपजनश्छान्दसः । "स्तम्बे क च" इति विहितः कप्रत्ययो बहुलवचनाद् अत्रापि द्रष्टव्यः । यद्वा सहस्रं हन्यन्ते आताड्यन्ते अनेनेति सहस्रघ्नम्[3] । "घञर्थे कविधानम्" इति करणे कप्रत्ययः । शतवधम् शतसंख्याकस्य प्राणिजातस्य मारकम् । यद्वा शतं सहस्रम् इति अपरिमितनाम । अपरिमितस्य विश्वस्य संहारकम् इत्यर्थः । [शिखण्डि[*]] मयूरपिच्छादिनिर्मिताः शिखण्डास्तद्युक्तम् । तस्मै त्वदीयाय धनुषे नमोस्तु ॥ इदानीम् इषुं नमस्करोति । रुद्रस्य रोदयितुर्देवस्य इषुर्बाणः चरति सर्वत्र अप्रतिहतगतिर्वर्तते । देवहेतिः देवस्य संबन्धिनी हननसाधनभूता शक्तिरेव सेत्यर्थः । तस्यै इष्वै नमोस्तु नमस्कारो भवतु । इतः अस्मात् अस्मदीयात् स्थानाद् यतमस्याम् यस्यां दिशि वर्तते तस्यां दिशि अवस्थितायै तस्यै नमोस्त्विति संबन्धः ॥

तृतीया ॥

यो[१]ऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।
पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥ १३ ॥

यः । अभिऽयातः । निऽलयते । त्वाम् । रुद्र । निऽचिकीर्षति ।
पश्चात् । अनुऽप्रयुङ्क्षे । तम् । विद्धस्य । पदनीःऽइव ॥ १३ ॥

---

१ K D S̈[m] Cs १ for ३. We with A B B̈[h] C E K̈[m] R.

---

1 S' °हिरण्मया°. 2 S' सहस्रघ्नं. 3 S' सहस्रघ्नं.

हे रुद्र यः पुरुषस्त्वया अभियातः अभिगतो निलयते पुरतः स्थातुम् अशक्तः पलायते । यद्वा तत्रैव निलीनो भवति [न च केवलं निलीनो भवति] प्रत्युत त्वां निचिकीर्षति निकर्तुं हिंसितुम् इच्छति । ⧗ नि-पूर्वः करोतिर्हिंसने वर्तते । कृञ् हिंसायाम् इति प्रकृत्यन्तरं वा ⧗ । हे देव तम् अपकृतवन्तं जनं पश्चात् अनन्तरमेव त्वम् अनुप्रयुङ्क्षे तत्कृतस्य अपकारस्य अनुप्रयोगं करोषि । यथापराधं दण्डयसीत्यर्थः । तत्र दृष्टान्तः । विद्धस्य शस्त्रहतस्य पुरुषस्य पदनीरिव तदीयानि पदानि भूमौ निक्षिप्तानि नयन्[1] । यत्र शत्रुर्निवसति तावत्पर्यन्तं गमयन् पुरुषः निलीनं शत्रुम् उपलभ्य प्रतिविध्यति तद्वद् इत्यर्थः ॥

चतुर्थी ॥

भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।
ताभ्यां नमो यतमस्यां दिशी३तः[1] ॥ १४ ॥

भवारुद्रौ । सऽयुजा । सम्ऽविदानौ । उभौ । उग्रौ । चरतः । वीर्याय ।
ताभ्याम् । नमः । यतमस्याम् । दिशि । इतः ॥ १४ ॥

भवश्च रुद्रश्च भवारुद्रौ । ⧗ "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ् आदेशः ⧗ । सयुजा सयुजौ समानं युञ्जानौ मित्रभूतौ संविदानौ समानं जानानौ । ऐकमत्यं गतावित्यर्थः । ⧗ विद ज्ञाने । अस्मात् संपूर्वात् "समो गम्यृच्छि॰" इति आत्मनेपदम् ⧗ । तौ उभौ उग्रौ उद्गूर्णबलौ परैरप्रधृष्यौ सन्तौ वीर्याय । ⧗ "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाच्चतुर्थी ⧗ । वीर्यम् वीरकर्म चरतः अनुतिष्ठतः । यद्वा उग्रौ दुष्प्रधर्षौ चरतः सर्वत्र वर्तेते । किमर्थम् । वीर्याय । ⧗ तादर्थ्ये चतुर्थी ⧗ । स्ववीर्यप्रकटनार्थम् । ताभ्यां भवारुद्राभ्यां नमोस्तु । दूरस्थयोरेव तयोर्नमस्कारः कर्तव्यः न संनिधानम् अपेक्षणीयम् तस्यार्तिकरत्वात्[2] इत्यभिप्रेत्याह यतमस्याम् इति । इतः

---

१ VK १ for ३. We with AB$\overset{h}{B}$CDE$\overset{m}{K}$R$\overset{m}{S}$Cs. २ P दि॒शि॒. We with $\overset{2}{P}$JCp.

---

1 S′ नयत्. 2 S′ तस्याति॰.

अस्मात् अस्मदावासस्थानाद् यतमस्यां दिशि यस्यां कस्यांचिद् दिशि तौ वर्तेते तत्रस्थयोरेव तयोर्नमस्कारः । नमस्कारार्थमपि संनिहितौ मा भूताम् इत्यर्थः ॥

पञ्चमी ॥

नम॑स्तेऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते ।

नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नम॑ः ॥ १५ ॥

नम॑ः । ते॒ । अ॒स्तु॒ । आ॒ऽय॒ते । नम॑ः । अ॒स्तु॒ । प॒रा॒ऽय॒ते ।

नम॑ः । ते॒ । रु॒द्र॒ । तिष्ठ॑ते । आसी॑नाय । उ॒त । ते॒ । नम॑ः ॥ १५ ॥

हे रुद्र आयते अस्मदाभिमुख्येन गच्छते ते तुभ्यं नमोस्तु । तथा परायते पराङ्मुखं गच्छते तुभ्यं नमोस्तु । ॥आङ्पूर्वात्परापूर्वाच्च इण् गतौ इत्यस्मात् लटः शत्रादेशः । "इणो यण्" इति यण् आदेशः । "शतुरनुमः॰" इति विभक्तेरुदात्तत्वम्॥ । आगमनं परागमनं च विहाय यत्रक्वापि तिष्ठते [ते] तुभ्यं नमोस्तु । उत अपि च आसीनाय स्वस्थाने उपविष्टाय ते तुभ्यं नमः ॥

षष्ठी ॥

नम॑ः सा॒यं नम॑ः प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑ ।

भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॒मक॑रं॒ नम॑ः ॥ १६ ॥

नम॑ः । सा॒यम् । नम॑ः । प्रा॒तः । नम॑ः । रात्र्या॑ । नम॑ः । दिवा॑ ।

भ॒वाय॑ । च॒ । श॒र्वाय॑ । च॒ । उ॒भाभ्या॑म् । अ॒क॒र॒म् । नम॑ः ॥ १६ ॥

हे रुद्र सायम् सायंकाले तुभ्यं नमोस्तु । [प्रातः] प्रातःकाले प्रभातसमये च तुभ्यं नमोस्तु । तथा रात्र्या रात्रिसमये तुभ्यं नमोस्तु । दिवा दिवससमयेपि तुभ्यं नमोस्तु । एतेन नमस्कारस्य सार्वकालिकत्वम् उक्तम् । "भवाशर्वौ मृडतम्" इति यौ देवौ प्राक् सह निर्दिष्टौ तत्र भवाय च नमः शर्वाय च नमः । उभाभ्यां परस्परानुरागेण संयुक्ताभ्यां

१ A B[h] C K[m] R नम॑स्ते अस्त्वा॰. We with B K D S[m] V Cs.

1 S' omits ॰त्परापूर्वा॰. 2 S' omits तुभ्यं नमोस्तु । दिवा दिवससमये॰.

च नमः अकरम् अहं नमस्करोमि । करोतेश्छान्दसो लुङ् । "कृमृदृरुहिभ्यश्छन्दसि" इति च्लेः अङ् आदेशः । "ऋदृशोऽङि गुणः" इति गुणः ॥

सप्तमी ॥

सहस्राक्षमतिपश्यं पुरस्ताद् रुद्रमस्यन्तं बहुधा विपश्चितम्।
मोपाराम जिह्वयेयमानम् ॥ १७ ॥

सहस्रऽअक्षम् । अतिऽपश्यम् । पुरस्तात् । रुद्रम् । अस्यन्तम् । बहुऽधा । विपःऽचितम् ।
मा । उप । अराम । जिह्वया । ईयमानम् ॥ १७ ॥

सहस्राक्षम् सहस्रसंख्याकैः अक्षिभिर्युक्तं पुरस्तात् पुरोभागे अतिपश्यम् अतिशयेन अतिक्रम्य वा पश्यतीति अतिपश्यः । दृशिर् प्रेक्षणे इत्यस्मात् "पाघ्राध्माधेट्दृशः [शः]" इति शप्रत्ययः । "पाघ्राध्मास्था०" इत्यादिना पश्यादेशः । यद्वा पुरस्तात् इति उत्तरत्र संबध्यते । पुरस्तात् पूर्वस्यां दिशि बहुधा बहुप्रकारम् अस्यन्तम् शरजालं क्षिपन्तं विपश्चितम् मेधाविनं सूक्ष्मदर्शिनं जिह्वया ईयमानम् जिह्वाग्रेण कृत्स्नं जगद् व्याप्नुवन्तम् । भक्षणार्थं लिहन्तम् इत्यर्थः । एवंभूतं रुद्रं मा उपाराम मा उपगच्छाम । अर्तेर्माङि लुङि "सर्तिशास्त्यर्तिभ्यश्च" इति च्लेः अङ् आदेशः ॥

अष्टमी ॥

श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्वस्मै ॥ १८ ॥

श्यावऽअश्वम् । कृष्णम् । असितम् । मृणन्तम् । भीमम् । रथम् । केशिनः । पादयन्तम् ।
पूर्वे । प्रति । इमः । नमः । अस्तु । अस्मै ॥ १८ ॥

श्यावाश्वम् श्यावाः कपिशवर्णा अश्वा यस्य स तथोक्तः तम् कृष्णम्

कृष्णवर्णम् असितम् सितेतरपरिच्छदम् मृणन्तम् हिंसन्तम् । मृ हिंसायाम् । प्वादित्वात् ह्रस्वः । भीमम् बिभेति अस्माद् इति भीमो भयंकरः । "भीमादयोपादाने" इत्यपादाने भियः षुग्वा [उ॰ १.१४५] इति मक् प्रत्ययः । एतत्संज्ञकं रुद्रं केशिनः केशी नाम असुरः । तस्य रथं पादयन्तम् भङ्क्त्वा भूमौ क्षिपन्तम् एवंभूतं देवं पूर्वे अन्येभ्यः स्तोतृभ्यः प्रथमभाविनः सन्तो वयं प्रतीमः जानीमः । रक्षकत्वेन अवगच्छाम इत्यर्थः । अस्मै रुद्राय नमोस्तु ॥

नवमी ॥

मा नोभि स्रा मर्त्यं[1] देवहेतिं[2] मा नः क्रुधः पशुपते नमस्ते ।
अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥ १९ ॥

मा । नः । अभि । स्राः । मर्त्यम्[3] । देवऽहेतिम् । मा । नः । क्रुधः । पशुऽपते । नमः । ते ।
अन्यत्र । अस्मत् । दिव्याम् । शाखाम् । वि । धूनु ॥ १९ ॥

हे रुद्र देवहेतिम् देवसंबन्धि आयुधं वज्रात्मकम् आत्मीयाम् इषुं वा नः अस्माकं मर्त्यम्* मरणधर्माणं जनम् अभिलक्ष्य मा स्राः मा विसृज । सृजतेः "माङि लुङ्" । मध्यमैकवचने च्लेः सिच् । "सृजिदृशोर्झल्यम् अकिति" इति अम् आगमः । वृद्धौ "झलो झलि" इति सिचो लोपः । "बहुलं छन्दसि" इति इडभावः । "हल्ङ्याब्भ्यः॰" इति सिलोपः । छान्दसो जकारलोपः । हे पशुपते नः अस्मभ्यं मा क्रुधः क्रुद्धो मा भूः । क्रुध कोपे । माङि लुङि पुषादित्वात् च्लेः अङ् आदेशः । ते तुभ्यं नमोस्तु । देवहेतिविसर्जनस्य अवकाशम् आह अन्यत्रेति । अस्मत् अस्मत्तः अन्यत्र देशे दिव्याम् दिवि भवां शाखाम् शाखावत् प्रसृतां देवहेतिं वि धूनु विसृज । धूञ्

१ B मर्त्यं. We with A B̊ C D E K K̊ R S̊ V Cs. Sâyaṇa here has doubtless been either careless or followed an inferior reading. २ B °हुतं changed into °हितं. We with A B̊ C D E K K̊ R S̊ V Cs. ३ P मृत्यम्. Cp मर्त्यं changed to मर्त्यं. We with P J.

कम्पने । स्वादित्वात् श्नुप्रत्ययः । “उतश्च प्रत्ययाद्॰” इति हेर्लुक् ॥

दशमी ॥

मा नो॑ हिंसीरधि नो ब्रूहि परि॑ णो वृङ्धि मा क्रुधः ।
मा त्वया सम॑रामहि ॥ २० ॥ (६)

मा । नः । हिंसीः । अधि । नः । ब्रूहि । परि॑ । नः । वृङ्धि । मा । क्रुधः ।
मा । त्वया॑ । सम् । अरामहि ॥ २० ॥ (६)

हे रुद्र नः अस्मान् मा हिंसीः अस्मद्विषये हिंसां मा कृथाः । नः अस्मान् अधि ब्रूहि आधिक्येन कथय । अनुग्राह्यत्वेन पक्षपातवचनम् अधिवचनम् । नः अस्मान् परि वृङ्धि तवायुधविषयात् परिहर । अस्मान् परिहृत्य अन्यत्र त्वद्धेतिः प्रवर्तताम् इत्यर्थः । मा क्रुधः अस्मद्विषये क्रुद्धो मा भूः । एवंभूतेन त्वया वयं मा समरामहि संगच्छामहै । उक्तार्थम् एतत् [७] ॥

[इति] एकादशकाण्डे प्रथमेनुवाके षष्ठं सूक्तम् ॥

“मा नो गोषु” इति सूक्तस्य स्वस्त्ययनादिकर्मसु विनियोगः पूर्वमेव उक्तः ॥

तत्र प्रथमा ॥

मा नो॑ गोषु पुरु॑षेषु मा गृधो नो अजाविषु॑ ।
अन्यत्रो॑ग्र वि व॑र्तय पिया॑रूणां[२] प्रजां ज॑हि ॥ २१ ॥

मा । नः । गोषु॑ । पुरु॑षेषु । मा । गृधः । नः । अजऽअविषु॑ ।
अन्यत्र॑ । उग्र । वि । वर्तय । पिया॑रूणाम् । प्रऽजाम् । जहि ॥ २१ ॥

हे रुद्र नः अस्माकं संबन्धिषु गोषु पुरुषेषु पुत्रभृत्यादिषु च मा गृधः हिंसितुम् अभिकाङ्क्षां मा कृथाः । [तथा नः अस्माकम् अजाविषु अजेषु अविषु च मा गृधः ।] गृधु अभिकाङ्क्षायाम् । माङि लुङि पुषादित्वात् च्लेः अङ् आदेशः । [हे उग्र उद्गूर्णबल

१ B corrects into हासी॰. We with AB^h CDEKK^m RS^m VCs. २ B पिया॑रुणां.

तव हेतिम् अन्यत्र असत्तः अन्यस्मिन् स्थाने पियारूणां प्रजाया वि वर्तय गमय क्षिप । तथा कृत्वा च पियारूणाम् देवहिंसकाना प्रजां जहि । [जहीति । "हन्तेर्जः" इति जादेशे] तस्य "असिद्धवद् अत्रा भात्" इति असिद्धत्वात् "अतो हेः" इति लुगभावः ॥

द्वितीया ॥

यस्य॑ त॒क्मा का॑सिका हे॒तिरेक॒मश्व॑स्येव॒ वृष॑ण॒: क्रन्द॒ एति॑ ।
अ॒भि॒पू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥ २२ ॥

यस्य॑ । त॒क्मा । का॑सिका । हे॒तिः । एक॑म् । अश्व॑स्यऽइव । वृष॑णः । क्रन्द॑ः । एति॑ ।
अ॒भि॒ऽपू॒र्वम् । नि॒ःऽनय॑ते । नम॑ः । अ॒स्तु । अ॒स्मै॒ ॥ २२ ॥

तक्मा [कृच्छ्रेण] जीवनप्रापिका । [तकि कृच्छ्र]जीवने । अस्माद् "अन्येभ्योपि दृश्यन्ते" इति मनिन् । कासिका । [कासृ शब्दकुत्सायाम] । कुत्सितशब्दकारिणी आर्तस्वरकरी ज्वरादिपीडा [यस्य] रुद्रस्य हेतिः हननसाधनम् आयुधम् एकम् अपकारिणं पुरुषं वृषणः सेचनसमर्थस्य अश्वस्य क्रन्दः हेषाशब्द इव एति प्राप्नोति । सा हेतिस्तत्र अभिपूर्वम् पूर्वपूर्वम् अभिलक्ष्य तत्र योयः प्रथमभावी तंतं निर्णयते निःशेषेण गमयति नाशं प्रापयति । अस्मै ज्वराद्युपद्रवकारिणे रुद्राय नमोस्तु ॥

तृतीया ॥

यो॒३॑[1]न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोय॑ज्वनः प्रमृ॒णन् दे॑वपी॒यून् ।
तस्मै॒ नमो॑ द॒शभि॒ः शक्व॑रीभिः ॥ २३ ॥

यः । अ॒न्तरि॑क्षे । तिष्ठ॑ति । विऽस्त॑भितः । अय॑ज्वनः । प्र॒ऽमृ॒णन् । दे॒वऽपी॒यून् ।
तस्मै॑ । नम॑ः । द॒शऽभि॒ः । शक्व॑रीभिः ॥ २३ ॥

---

१ B^h D S^m Cs have no kampa. B K V यो॑३॒॰. We with A C E K^m R.

यो रुद्रः अन्तरिक्षे आकाशे निराधारप्रदेशे विष्टभितः विशेषेण स्तभितः निरुद्धगतिस्तिष्ठति । किं कुर्वन् । अयज्वनः दर्शपूर्णमासादियागेन इष्टवन्तो जना यज्वानः तद्विपरीता अयज्वानः तान् देवपीयून् देवानां हिंसकान् जनान् प्रमृणन् प्रकर्षेण हिंसन् । तस्मै रुद्राय दशभिः शक्करीभिः । शक्कर्य इति अङ्गुलिनाम । कर्मसु शक्ताभिः[1] अङ्गुलिभिः नमोस्तु । अञ्जलिबन्धनेन प्रणामं कुर्म इत्यर्थः ॥

चतुर्थी ॥

तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि ।
तव॑ य॒क्षं प॑शुपते अ॒प्स्व१॒॑न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥ २४ ॥

तुभ्य॑म् । आ॒र॒ण्याः । प॒शवः॑ । मृ॒गाः । वने॑ । हि॒ताः । हं॒साः । सु॒ऽप॒र्णाः ।
श॒कु॒नाः । वयां॑सि ।
तव॑ । य॒क्षम् । प॒शु॒ऽप॒ते॒ । अ॒प्ऽसु । अ॒न्तः । तुभ्य॑म् । क्ष॒र॒न्ति॒ । दि॒व्याः ।
आपः॑ । वृ॒धे ॥ २४ ॥

हे पशुपते पशूनां पालयितर्महादेव तुभ्यं त्वदर्थम् आरण्याः अरण्ये भवाः पशवः । तानेव यथेच्छं स्वीकुरु । ग्राम्यान् पशून् मा बाधिष्ठा इत्यर्थः । आरण्यानेव पशून् निर्दिशति । वने अरण्ये हिताः विधात्रा स्थापिता मृगाः हरिणशार्दूलसिंहाद्याः । [हंसाः] एतत्संज्ञाः पक्षिणः । सुपर्णाः शोभनपतनाः श्येनाः । शकुनाः अन्ये च शकुनयो वनचराः पक्षिणः । एवमात्मकानि वयांसि पक्षिजातानि हे रुद्र त्वदर्थं भागत्वेन कल्पितानि । तव त्वदीयं यक्षम् पूज्यं स्वरूपम् अप्सु अन्तः उदकेषु मध्ये वर्तते अतः तुभ्यं त्वदर्थं मृधे* उन्दनाय । ⌛शृधु मृधु उन्दे । अस्मात् संपदादिलक्षणो भावे क्विप्⌛ । अभिषेकाय दिव्याः दिवि भवा आपः क्षरन्ति प्रवहन्ति । अस्मदुपभोग्यम् उदकमपि मा स्पृक्ष इत्यर्थः ॥

---

१ ABCER ३ for १. B[h] has no kampa. We with K K[m] S[m] V Cs.

---

1 S′ सक्ताभिः.

पञ्चमी ॥

शिंशुमारा अजगराः[1] पुरीकया जषा[2] मत्स्या रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान्[3] परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्[4] समुद्रे ॥ २५ ॥

शिंशुमाराः । अजगराः । पुरीकयाः[5] । जषाः[6] । मत्स्याः । रजसाः । येभ्यः । अस्यसि ।
न । ते । दूरम् । न । परिऽस्था । अस्ति[7] । ते । भव । सद्यः । सर्वान्[8] । परि । पश्यसि । भूमिम् । पूर्वस्मात् । हंसि । उत्तरस्मिन् । समुद्रे ॥ २५ ॥

आरण्यपशुवज्जलचरप्राणिनामपि रुद्रभागत्वम् उच्यते । शिंशुमाराः नक्रविशेषाः । अजगराः सर्पविशेषाः । पुलीकयाद्या* जलचराः प्राणिविशेषाः । हे रुद्र त्वदर्थम् एते सर्वे जलचराः प्राणिन इत्यर्थः । रजसा* आत्मीयेन तेजसा येभ्यः जलचरप्राणिभ्यः अस्यसि आयुधं क्षिपसि । हे भव ते तव सर्वगतस्य दूरम् विप्रकृष्टं नैवास्ति । [ते] परिष्ठा परिहृत्य स्थिता प्रजापि न विद्यते । यतस्त्वं सर्वाम्* कृत्स्नां भूमिं सद्यः क्षणादेव परि पश्यसि परितः अवलोकयसि । तथा पूर्वस्मात् पुरोवर्तिनः समुद्रात् उत्तरस्मिन् उत्तरदिग्वर्तिनि समुद्रे जलधौ हंसि क्षणादेव गच्छसि । ॥ हन्तिरत्र गत्यर्थः ॥ । अतः सर्वगतस्य तव विप्रकृष्टं नैवास्ति तथा च शिंशुमारादयस्तव नित्यसंनिहिता इत्यर्थः ॥

षष्ठी ॥

मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।
अन्यत्रास्मद् विद्युतं पातयैताम्[9] ॥ २६ ॥

---

१ B K K^{m} B^{h} omit the visarga. २ V झषा; B^{h} C E जखा; R जघा. We with A D K K^{m} S^{m} Cs. ३ A S^{m} सर्वा परि. We with A B B^{h} C D E K K^{m} V R Cs. ४ B °द्धंस्युत्तर°. ५ So P P^{2} J. Cp पुलीकयाः. ६ P J जखाः corrected into जषाः. ७ P J Cp अस्ति. We with P^{2}. ८ P P^{2} सर्वाम्. We with J Cp. ९ B पातयैतम्.

मा । नः । रुद्र । तक्मना । मा । विषेण । मा । नः । सम् । स्राः ।
दिव्येन । अग्निना ।
अन्यत्र । अस्मत् । विऽद्युतम् । पातय । एताम् ॥ २६ ॥

हे रुद्र तक्मना कृच्छ्रजीवनकारिणा ज्वरादिरोगेण त्वदीयेन आयुधेन नः अस्मान् मा सं स्राः मा संसृज । तथा विषेण स्थावरजङ्गमोद्भवेन प्राणापहारिणा मा संसृज । तथा दिव्येन दिवि भवेन अग्निना वैद्युतरूपेण तेजसा नः अस्मान् मा संसृज । अस्मत्तः अन्यत्र आरण्यपश्वादिषु एतां विद्युतम् त्वदायुधभूतां विद्योतमानाम् अशनिं पातय प्रक्षिप ॥

सप्तमी ॥

भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व१न्तरिक्षम् ।
तस्मै नमो यतमस्यां दिशीऽइतः ॥ २७ ॥

भवः । दिवः । भवः । ईशे । पृथिव्याः । भवः । आ । पप्रे । उरु ।
अन्तरिक्षम् ।
तस्मै[1] । नमः । यतमस्याम् । दिशि[3] । इतः ॥ २७ ॥

भवः एतत्संज्ञो देवो दिवः द्युलोकस्य ईशे ईष्टे । द्युलोकम् ईशितव्यत्वेन अधितिष्ठतीत्यर्थः । ईश ऐश्वर्ये । "लोपस्त आत्मनेपदेषु" इति तलोपः । "अधीगर्थदयेशाम्॰" इति कर्मणि षष्ठी । तथा स एव भवः पृथिव्याः भूलोकस्यापि ईशे ईष्टे । तथा उरु विस्तीर्णम् अन्तरिक्षम् द्यावापृथिव्योर्मध्ये वर्तमानं लोकं स एव भवः आ पप्रे स्वतेजसा आपूरयति । प्रा पूरणे । अस्मात् छान्दसो लिट् । "आतो लोप इटि च" इति आल्लोपः । तस्मै त्रैलोक्यव्यापिने । अन्यद् उक्तार्थम् [१४] ॥

अष्टमी ॥

भवं राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।

---

१ B B̊ C D E K K̊ R S̊ Cs तस्यै. We with P V A. २ P̊ J Cp तस्यैं. We with P.
३ P Cp दिशि. We with P̊ J.

य: श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेस्य मृड ॥ २८ ॥

भव । राजन् । यजमानाय । मृड । पशूनाम् । हि । पशुऽपतिः । बभूथ । य: । श्रत्ऽदधाति । सन्ति । देवाः । इति । चतुःऽपदे । द्विऽपदे । अस्य । मृड ॥ २८ ॥

हे राजन् सर्वस्याधिपते हे भव यजमानाय त्वदर्थं यागं कुर्वते जनाय मृळ* सुखय । त्वं खलु पशूनां पशुपतिर्बभूथ "तवेमे पञ्च पशवो विभक्ताः" [९] इति प्रागुदीरितानां गवाश्वादीनां पशूनां पतिः पालयिता भवसि । पशूनां पशुपतिरिति वृत्त्यवृत्तिभ्यां बहुत्वं स्वामित्वं च प्रतिपाद्यते । "बभूयाततन्थ जगृभ्म ववर्थेति निगमे" इति भवतेस्थलि इडभावो निपात्यते । हि यस्माद् एवं तस्माद् यजमानाय मृडेति संबन्धः ॥ य आस्तिकः पुरुषो देवा इन्द्रादयो रक्षकाः सन्तीति श्रद्दधाति आद्रियते । विश्वसितीत्यर्थः । अस्य श्रद्दधानस्य पुरुषस्य संबन्धिने चतुष्पदे गवाश्वादये द्विपदे पुत्रभृत्यादिरूपाय च मृळ* सुखय ॥

नवमी ॥

मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।
मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥ २९ ॥

मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । वहन्तम् । उत । मा । नः । वक्ष्यतः ।
मा । नः । हिंसीः । पितरम् । मातरम् । च । स्वाम् । तन्वम् । रुद्र । मा । रिरिषः । नः ॥ २९ ॥

हे रुद्र नः अस्माकं संबन्धिनं महान्तम् प्रवयसं वृद्धं मा हिंसीः । उत अपि च नः अस्माकम् अर्भकम् शिशुं मा हिंसीः । नः अस्माकं संबन्धिनं वहन्तम् भारवहनक्षमं मध्यवयस्कं पुरुषं मा हिंसीः । उत अपि च वक्ष्*तः[1] कृतवहनव्यापारान् पुरुषान् नः अस्मदीयान् मा हिं-

1 This is the reading of Sâyaṇa's text also.

सीः । तथा नः अस्मदीयं पितरं मातरं च मा हिंसीः । तथा नः अस्माकं स्वाम् स्वकीयां तन्वम् शरीरं मा रीरिषः मा हिंसीः । ⧗ रिष रुष हिंसायाम् । ण्यन्तात् लुङि चङि रूपम् । "न माङ्योगे" इति अडभावः ⧗ ॥

दशमी ॥

रुद्रस्यैलब[1]कारेभ्योऽसंसूक्तगिलेभ्यः ।
इदं महास्येभ्यः श्वभ्यो[2] अकरं नमः ॥ ३० ॥

रुद्रस्य । ऐलबऽकारेभ्यः । असंसूक्तऽगिलेभ्यः ।
इदम् । महाऽआस्येभ्यः । श्वऽभ्यः । अकरम् । नमः ॥ ३० ॥

अतः परं महादेवस्य परिवारा[1] नमस्कारेण प्रार्थ्यन्ते । रुद्रस्य महादेवस्य संबन्धिभ्यः ऐलवकारेभ्यः[*] । ⧗ इल प्रेरणे । अस्माद् भावे घञ् । ततो मत्वर्थीयो वकारः ⧗ । एलवानि प्रेरणयुक्तानि कर्माणि कुर्वन्तीति एलवकाराः कर्मकराः प्रमथगणाः । तेभ्यः अहं नमस्करोमि । तथा असंसूक्तगिलेभ्यः । सम्यक् सूक्तं शोभनं भाषितं संसूक्तम् । तद्विपरीतम् असंसूक्तम् असमीचीनम् अशोभनवचनं गृणन्ति भाषन्त इति असंसूक्तगिलाः । ⧗ गॄ[2] शब्दे इत्यस्माद् औणादिक इलच् प्रत्ययष्टिलोपश्च ⧗ । यद्वा तादृग्भाषणं यथा भवति तथा गिरन्ति भक्षयन्तीति असंसूक्तगिलाः । ⧗ गॄ निगरणे इत्यस्मात् पचाद्यच् । गुणं बाधित्वा "ॠत इद्धातोः" इति व्यत्ययेन इत्वम् । "अचि विभाषा" इति लत्वम् । यद्वा गल अदने इत्यस्माद् वा[3] अच् प्रत्ययः । छान्दसम् इत्वम् ⧗ । एवंभूतेभ्यो रुद्रगणेभ्यो नमस्करोमि ॥ महास्येभ्यः महत् प्रभूतम् आस्यं मुखविवरम् एषाम् अस्तीति महास्याः । ⧗ "आन्महतः[4]°" इति आत्वम् ⧗ । मृगयाविहारार्थं[4] किरातवेषधारिणो देवस्य संबन्धिभ्यः [श्वभ्यः] सारमेयेभ्यः इदं नमः अ-

---

१ So we with all our MSS. and vaidikas. २ B श्वेभ्यों.

---

1 S′ परिवारनम°. 2 S′ गृ श°. 3 So S′. Have we to add some such words as गल स्रावे इत्यस्माद्? 4 S′ has the words आन्महत इति आत्त्वम् *after* मृगयाविहारार्थं.

करम् करोमि । ¤ करोतेश्छान्दसो लुङ् । "कृमृदृरुहिभ्यश्छन्दसि" इति च्लेः अङ् आदेशः ¤ ॥

एकादशी ॥

नम॑स्ते घोषिणी॑भ्यो नम॑स्ते के॒शिनी॑भ्यः ।
नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ ।
नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥ ३१ ॥ (७)

नमः॑ । ते॒ । घोषिणी॑भ्यः । नमः॑ । ते॒ । के॒शिनी॑भ्यः ।
नमः॑ । नमः॑ऽकृताभ्यः । नमः॑ । स॒म्ऽभु॒ञ्ज॒तीभ्यः॑ ।
नमः॑ । ते॒ । दे॒व॒ । सेना॑भ्यः । स्व॒स्ति । न॒ः । अभ॑यम् । च॒ । न॒ः ॥ ३१ ॥ (७)

हे रुद्र ते त्वदीयाभ्यो घोषिणीभ्यः प्रभूतघोषयुक्ताभ्यः सेनाभ्यः नमोस्तु । तथा ते त्वदीयाभ्यः केशिनीभ्यः विपरीताकृतिकेशयुक्ताभ्यः विकीर्णकेशयुक्ताभ्यो वा सेनाभ्यो नमोस्तु । याश्च त्वदीयाः सेना नमस्कृताः चण्डेश्वरप्रभृतयः ताभ्यश्च नमोस्तु । संभुञ्जतीभ्यः सहभोजनं कुर्वतीभ्यः सेनाभ्यो नमोस्तु । हे देव रुद्र ते त्वदीयाभ्यः उक्तव्यतिरिक्ताभ्यः सेनाभ्यो नमोस्तु । हे देव त्वत्प्रसादात् नः अस्मभ्यं स्वस्ति क्षेमम् अभयं च*न[1] भयराहित्यमपि भवतु । स्वस्तिशब्दयोगात् स्वस्त्ययनकर्मणि विनियोगः । भयराहित्यप्रार्थनाच्च अद्भुतशान्तावपि । इति लिङ्गानुसारेण सर्वत्र विनियोगो द्रष्टव्यः ॥

सप्तमसूक्तम् ।

इति सायणाचार्यविरचिते अथर्वसंहिताभाष्ये
एकादशकाण्डे प्रथमोनुवाकः ॥

द्वितीयेनुवाके षट् सूक्तानि । तत्र "तस्यौदनस्य" इत्यादिसूक्तत्रयम् अर्थसूक्तम् । तेन बृहस्पतिसवाख्ये सवयज्ञे हविरभिमर्शनसंपातदातृवाचनदानादीनि कर्माणि कुर्यात् ॥

तथा अभिचारकर्मणि सवविधानेन ओदनं पक्त्वा पृषातकेन उपसिच्य

1 Sâyaṇa's text also: चन for our च नः.

अनेन अर्थसूक्तेन अभिमृश्य संपात्य अभिमन्त्र्य द्वेष्याय प्रयच्छेत्। द्वेष्यं वा अनेन अर्थसूक्तेन अभिमृशेत् हुताज्यशेषेण संपातयेद् वा ॥

विपक्षे बाधपुरःसरम् ओदनस्यैव प्राशितृत्वं प्राशितव्यत्वं च अग्रे वक्ष्यते। तत्र प्राशितुरोदनस्य शिरःप्रभृतीनि अङ्गानि कल्पयति ॥

(१) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥ १ ॥

तस्य। ओदनस्य। बृहस्पतिः। शिरः। ब्रह्म। मुखम् ॥ १ ॥

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥ २ ॥

द्यावापृथिवी इति। श्रोत्रे इति। सूर्याचन्द्रमसौ। अक्षिणी इति। सप्तऽऋषयः। प्राणापानाः ॥ २ ॥

तस्य प्रसिद्धस्य विराडात्मना भावनीयस्य ओदनस्य बृहस्पतिर्देवः शिरः मूर्धा। तस्यापि कारणभूतं यद् ब्रह्म तत् ओदनस्य मुखम् आस्यम् ॥ द्यावापृथिवी द्यौश्च पृथिवी च द्यावापृथिव्यौ। ⧗ "दिवो द्यावा" इति द्यावादेशः ⧗। ते उभे अस्य ओदनस्य विराडात्मनः श्रोत्रे। ⧗ श्रवणेन्द्रियस्य एकत्वेपि तद्गोलकापेक्षया द्वित्वम् ⧗। सूर्याचन्द्रमसौ सूर्यः सर्वस्य प्रेरक आदित्यः। ⧗ "[राज]सूयसूर्य॰" इति निपात्यते ⧗। चन्द्रम् आह्लादकरम् अमृतं मिमीते सर्वस्य जगतो निर्मिमीत इति चन्द्रमाः। ⧗ चन्द्रे माङो डित् इति [उ॰ ४,२२७] औणादिकः असिप्रत्ययः। सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ। "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ् आदेशः ⧗। तौ अस्य विराडात्मन ओदनस्य अक्षिणी चक्षुषी। ये सप्तऋषयः मरीच्यत्रि[1]प्रभृतयस्ते प्राणापानाः। मुखनासिकाभ्यां बहिर्निःसरन् वायुः प्राणः। अन्तः प्रविशन् वायुः अपानः। प्राणश्च अपानश्च प्राणापानौ। ये सप्तऋषयस्तेऽस्य प्राणापानात्मना भावनीया इत्यर्थः। ⧗ प्राणापानयोर्द्वित्वेपि उद्देश्यसंख्यापेक्षया तयोर्वृत्त्यपेक्षया[2] वा बहुवचननिर्देशः ⧗ ॥

1 S′ omits °त्रि° in मरीच्यत्रि°. 2 S′ वृत्तितदापेक्षया for तयोर्वृत्त्यपेक्षया. Or have we to correct: वृत्तितदपेक्षया?

इत्थम् ओदनस्य देवतारूपाणि अङ्गानि परिकल्प्य तत्साधनेष्वपि देवतारूपत्वं संपादयति ॥

चक्षुर्मुसलं काम उलूखलम् ॥ ३ ॥

चक्षुः । मुसलम् । कामः । उलूखलम् ॥ ३ ॥

दितिः शूर्पमदितिः शूर्पग्राही वातोपाविनक् ॥ ४ ॥

दितिः । शूर्पम् । अदितिः । शूर्पऽग्राही । वातः । अप । अविनक् ॥ ४ ॥

अस्य उक्तमहिमोपेतस्य ओदनस्य उपादानभूतव्रीह्यवहननार्थं यन्मुसलं तच्चक्षुः चक्षुरिन्द्रियम् । यत् उलूखलं स कामः अभिलाषः । मुसलोलूखले हविरवहननार्थे चक्षुरादिरूपेण भावनीये इत्यर्थः ॥ दितिः असुरमाता सैव परापवनार्थं शूर्पम् । अदितिः देवमाता सा शूर्पग्राही तस्य शूर्पस्य ग्रहीत्री । या शूर्पेण परापुनाति सा अदित्यात्मना भावनीयेत्यर्थः । वातः वायुः अपाविनक् व्रीहिभ्यस्तण्डुलानां विवेचयिता अभवत् । विवेचयितरि वायुबुद्धिः कार्येत्यर्थः । अत एव तैत्तिरीयके "वायुर्वो विविनक्तु" इति मन्त्रवर्णः [तै॰ सं॰ १.१.५.२] । ⌶विचिर् पृथग्भावे । अस्मात् लङि रुधादित्वात् श्नम् । "हल्ङ्याब्भ्यः॰" इति तिलोपे "चोः कुः" इति कुत्वम्⌶ ॥

ओदनस्य विराडात्मना उपासनम् अभिधित्सुस्तत्संबन्धिनां कणादीना तत्तद्वस्त्वात्मकत्वेन तस्य ओदनस्य सार्वात्म्यं प्रतिपादयति ॥

अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥ ५ ॥

अश्वाः । कणाः[२] । गावः । तण्डुलाः । मशकाः । तुषाः ॥ ५ ॥

कब्रु फलीकरणाः शरोभ्रम् ॥ ६ ॥

कब्रु । फलीऽकरणाः । शरः[४] । अभ्रम् ॥ ६ ॥

---

१ P सूर्पम्. We with P̊² J Cp. २ P कर्णः. We with P² J. ३ B K शिरो॰. V recognises both readings. A शीरो॰ changed to शरो॰. We with B^h C D E K^m R S^m Cs. ४ So P P² J Cp.

---

1 S′ अपविनक्.

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥ ७ ॥

श्यामम्। अयः। अस्य। मांसानि। लोहितम्। अस्य। लोहितम् ॥ ७ ॥

ये ओदनसंबन्धिनः कणास्ते अश्वाः। अश्वात्मना भावनीया इत्यर्थः। ओदनस्य उपादानभूता ये तण्डुलास्ते गावः। परापूतास्तुषा मशकाः क्षुद्रजन्तवः ॥ ये फलीकरणास्तत् कभ्रु*। कं शिर एव भ्रुवौ[1] यस्य प्राणिजातस्य तत् कभ्रु। शिरसो भ्रुवोश्च भेदो न दृश्यत इत्यर्थः। तथाविधप्राण्यात्मना फलीकरणा भावनीया इत्यर्थः। यद् अभ्रम् अन्तरिक्षे संचरन् मेघस्तद् अस्य शिरः*। "बृहस्पतिना शीर्ष्णा" इति [११. ४. १] प्राशने वक्ष्यमाणत्वात् तदुपयोगिदेवतात्मकं शिरः प्राग् उक्तम्। चेतनाचेतनात्मकस्य सर्वस्य जगतः ओदने भावनीयत्वप्रतिपादनप्रसङ्गायातम् एतच्छिर इति न पौनरुक्त्यम् ॥ श्यामम् श्यामवर्णं यत् अयः खनित्राद्युपादानं तत् अस्य विराडात्मन ओदनस्य मांसानि। यल्लोहितम् लोहितवर्णम् अयः ताम्रात्मकं लोके दृश्यते तत् सर्वम् अस्य ओदनस्य लोहितम् असृग् धातुः ॥

पुनरन्यान्यपि वस्तूनि ओदने संपादयति ॥

त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥ ८ ॥

त्रपु। भस्म। हरितम्। वर्णः। पुष्करम्। अस्य। गन्धः ॥ ८ ॥

खलः पात्रं स्फ्यावंसावीषे[१] अनूक्ये ॥ ९ ॥

खलः। पात्रम्। स्फ्यौ[२]। अंसौ। ईषे[३] इति। अनूक्येइति ॥ ९ ॥

आन्त्राणि जत्रवो गुदा वरत्राः ॥ १० ॥

आन्त्राणि। जत्रवः। गुदाः। वरत्राः ॥ १० ॥

ओदनपाकानन्तरभावि यद् भस्म तत् त्रपु सीसम्। तदात्मना भस्म भावनीयम् इत्यर्थः। यत् हरितम् हेम तत् अस्य ओदनस्य वर्णः।

---

१ K B[h] ॰वंसाविषे. We with A B C D E K[m] R S[m] V Cs. २ P स्फौ. P[2] स्फ्यै. We with J Cp. ३ P ईषे. We with P[2] J Cp.

---

1 S′ भ्रुवो.

यत् पुष्करम् कमलं तद् अस्य ओदनस्य गन्धः ॥ यः खलः व्रीह्यादिधान्यस्य पलालेभ्यो विवेचनस्थानं तद् अस्य पात्रम् धारणार्थम् आवपनम् । स्फौ[1] प्रवृद्धौ धान्याधारस्य शकटस्यावयवौ । तावस्य ओदनस्य अंसौ । स्फायी वृद्धौ इत्यस्माद् औणादिको डप्रत्ययः । ये शकटसंबन्धिन्यौ ईषे ते अस्य ओदनस्य अनूक्ये अंसयोर्मध्यदेहस्य च संधी । अनु उच्यते समवेयते संधीयत इति अनूक्या । कर्मणि ण्यत् । "चजोः कु घिण्ण्यतोः" इति कुत्वम् ॥ लोके सर्वप्राणिसंबन्धीनि आन्त्राणि यानि सन्ति तानि जत्रवः अनडुद्गीवाणां शकटयोजनार्था रज्जवः । अशितपीतान्नरससंचारणार्थाः सर्वप्राणिशरीरेषु या गुदास्ता अस्य वरत्राः ओदनसंबन्धिशकटलाङ्गलयोजनार्थाश्चर्मविकारा रज्जवः ॥

इत्थं सर्वात्मकस्य ओदनस्य स्थाल्यपिधानयोर्द्यावापृथिव्यात्मकताम् आह ॥

इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ॥११॥

इ॒यम् । ए॒व । पृ॒थि॒वी । कु॒म्भी । भ॒व॒ति॒ । राध्य॑मानस्य । ओ॒द॒नस्य॑ । द्यौः । अ॒पि॒ऽधान॑म् ॥ ११ ॥

इयं परिदृश्यमाना पृथिवी प्रथिता विस्तीर्णा भूमिरेव राध्यमानस्य पच्यमानस्य ओदनस्य उदीरितरीत्या सर्ववस्त्वात्मकस्य कुम्भी पाकार्था स्थाली भवति । द्यौः द्युलोकः अपिधानम् कुम्भीमुखस्य च्छादकं पात्रम् । द्यावापृथिव्योरन्तरालं सर्वम् अयम् ओदनो व्याप्य वर्तत इत्यर्थः ॥

पुनरन्यदपि अवयवजातम् अस्मिन् संपादयति ॥

सीता॒ः पर्श॑व॒ः सिक॑ता॒ ऊब॑ध्यम् ॥ १२ ॥

सीताः॑ । पर्श॑वः । सिक॑ताः । ऊब॑ध्यम् ॥ १२ ॥

सीताः कर्षणोत्पन्ना बीजावापार्था लाङ्गलपद्धतयः । ता अस्य ओदनस्य पर्शवः पार्श्वास्थीनि । नद्यादिषु याः सिकतास्ता अस्य ऊवध्यम् अर्धजीर्णतृणात्मकम् उदरगतं शकृत् ऊवध्यम् इति उच्यते ॥

पुनरन्यां संपत्तिम् आह ॥

1 S′ शकटस्यवायवौ.

ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥ १३ ॥

ऋतम् । हस्तऽअवनेजनम् । कुल्या । उपऽसेचनम् ॥ १३ ॥

ऋतम् इति उदकनाम । लोके विद्यमानं कृत्स्नम् उदकं हस्तावनेजनम् अस्य ओदनस्य हस्तप्रक्षालनार्थम् । कुल्या अल्पा सरित् । तत्रत्यं समस्तम् उदकम् अस्य ओदनस्य उपसेचनम् मिश्रणसाधनम् ॥

उदीरितमहिमोपेतस्य पाकार्था कुम्भी पृथिव्येवेत्युक्तम् । तस्या अग्नौ स्थापनप्रकारम् आह ॥

ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥ १४ ॥

ऋचा । कुम्भी । अधिऽहिता । आर्त्विज्येन । प्रऽइषिता ॥ १४ ॥

ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥ १५ ॥

ब्रह्मणा । परिऽगृहीता । साम्ना । परिऽऊढा ॥ १५ ॥

उदीरितलक्षणा ओदनपाकार्था कुम्भी स्थाली ऋचा ऋग्वेदेन अधिहिता अग्नावुपरि आहिता स्थापिता । आर्त्विज्येन ऋत्विजः अध्वर्यवः । तत्संबन्धिकर्मप्रतिपादकेन यजुर्वेदेन प्रेषिता अग्निं प्रगमिता । ब्रह्मणा ब्रह्मवेदेन आथर्वणेन[1] परिगृहीता परितो धारिता । साम्ना सामवेदेन पर्यूळ्हाँ पर्यूढा अङ्गारैः परिवेष्टिता ॥

इत्थम् अधिश्रितायां स्थाल्याम् ओदनपाकस्य अनुगुणं साधनम् आह ॥

बृहदायवनं रथन्तरं दर्विः ॥ १६ ॥

बृहत् । आऽयवनम् । रथम्ऽतरम् । दर्विः ॥ १६ ॥

बृहत् साम आयवनम् उदके प्रक्षिप्तानां तण्डुलानां मिश्रणसाधनं काष्ठम् । तथा रथन्तरं साम दर्विः ओदनोद्धारणसाधनम् ॥

ईदृग्विधस्य ओदनस्य पक्तॄन् दर्शयति ॥

ऋतवः पक्तार आर्तवाः समिन्धते ॥ १७ ॥

---

१ K V कुल्योप°. We with K^m B^h A B C D E R S^m Cs. २ B °इयचंनम्.

---

1 S′ आथर्वेण.

ऋतवः । पक्तारः । आर्तवाः । सम् । इन्धते ॥ १७ ॥

ऋतवः वसन्ताद्याः षट् अस्य ओदनस्य पक्तारः पचिक्रियायाः[1] कर्तारः । सर्वजगदात्मकौदनपाकस्य कालाधीनत्वात् नान्यः पक्तुं शक्नोतीत्यर्थः । आर्तवाः ऋतुसंबन्धिनः अहोरात्राः तत्तदृतौ जायमानाः प्राणिविशेषा वा समिन्धते संदीपयन्ति । यथा ओदनः पच्यते तथा अग्निं ज्वलयन्तीत्यर्थः । ञिइन्धी दीप्तौ ञि ॥

साक्षात्पक्तृत्वम् आदित्यस्यैवेति दर्शयति ॥

चरुं पञ्चबिलमुखं घर्मो३भीन्धे ॥ १८ ॥

चरुम् । पञ्चऽबिलम् । उखम् । घर्मः । अभि । इन्धे ॥ १८ ॥

चरुशब्दः ओदनवचनः । तस्य पाकार्था स्थाल्यपि चरुरित्युच्यते । तं चरुं पञ्चबिलम् "गावो अश्वाः पुरुषा अजावयः" [११. २. ९] इति प्रागुदीरितपञ्चपशूत्पत्तिहेतुत्वेन पञ्चधा विभिन्नमुखम् । यद्वा अन्तः पञ्चधा गृहकैः[2] प्रविभक्तावकाशश्चरुः पञ्चबिलः । यद् आह आपस्तम्बः[4] । "पञ्चबिलस्य चरोर्विज्ञायते आज्य आग्नेयः पूर्वस्मिन् बिले । दधन्यैन्द्रो "दक्षिणे । शृते[3] प्रतिदुहि नीतमिश्रे वा वैश्वदेवः पश्चिमे । अप्सु मैत्रावरुण उत्तरे । पयसि बार्हस्पत्यो मध्यमे" इति[4] । एवंभूतम् उखम् । चरुशब्दापेक्षया पुंलिङ्गता । उखां स्थालीं घर्मः प्रवर्ग्यात्मकस्तीक्ष्ण आदित्यः अभीन्धे अभितपति ॥

अस्यौदनस्य सर्वलोकप्राप्तिसाधनताम् आह ॥

ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः ॥ १९ ॥

ओदनेन । यज्ञऽवचः । सर्वे । लोकाः । सम्ऽआप्याः ॥ १९ ॥

इत्थं महाप्रभावेण पक्वेन ओदनेन यज्ञवचः यज्ञैः अग्निष्टोमादिभिः

---

१ P² रक्तारः. We with PJCP. २ AB °भींयंधे. We with B^h C D E K K^m R S^m V Cs.
३ P यज्ञऽवंचः. We with P² J CP.

---

1 S′ °क्रियायां. 2 S′ ग्रहकैः. 3 S′ श्रृणे. 4 See Sâyaṇa on *Taittirîya Saṁhitâ* I. 6. 1, where the author is merely called कल्पसूत्रकारः.

प्राप्तव्यत्वेन उच्यमानाः । वचेः कर्मणि विच् । सर्वे लोकाः भूम्यन्तरिक्षस्वर्गाद्याः समाप्याः सम्यग् आप्तुम् अर्हाः । सर्वलोकावाप्तिः अस्यौदनस्य फलम् इत्यर्थः ॥

पुनरपि अस्य महिमानम् आह ॥

यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥ २० ॥

यस्मिन् । समुद्रः । द्यौः । भूमिः । त्रयः । अवरऽपरम् । श्रिताः ॥ २० ॥

यस्मिन्नोदने समुद्रः उदधिः द्यौः आकाशः द्युलोको वा भूमिः पृथिवी एते त्रयः अवरपरं श्रिताः । एकः अवरः अधस्ताद् भवति अन्यः परस्ताद् यथा भवति तत् अवरपरम् । उत्तराधरभावेन स्थिता इत्यर्थः ॥

सर्वजगत्कल्पनास्पदत्वलक्षणं माहात्म्यम् अस्य दर्शयति ॥

यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥ २१ ॥

यस्य । देवाः । अकल्पन्त । उत्ऽशिष्टे । षट् । अशीतयः ॥ २१ ॥

यस्य ओदनस्य उच्छिष्टे यागावशिष्टे अंशे षडशीतयः षड्गुणिताशीतिसंख्याका देवा अकल्पन्त समर्था वीर्यवन्तः अभवन् । अथ वा । कृपिरन्तर्णीतण्यर्थः । सर्वं जगद् अकल्पयन् । तथा च अग्रे समाम्नास्यते । "उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः" [११. ९. १] इत्यादिना । तेन ओदनेन सर्वे लोकाः समाप्या इति संबन्धः ॥

उक्तं माहात्म्यं गुरुमुखात् ज्ञातव्यम् इत्यभिप्रेत्य शिष्यप्रश्नम् उद्भावयति ॥

तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥ २२ ॥

तम् । त्वा । ओदनस्य । पृच्छामि । यः । अस्य । महिमा । महान् ॥ २२ ॥

हे गुरो त्वा त्वाम् ओदनस्य तं महिमानं पृच्छामि । अस्यौदनस्य यो महिमा महान् अधिकतरः ॥

तत्र प्रतिवचने वर्जनीयं [दर्शयति] ॥

स य ओदनस्य महिमानं विद्यात् ॥ २३ ॥

सः । यः । ओदनस्य । महिमानम् । विद्यात्[1] ॥ २३ ॥

नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥ २४ ॥

न । अल्पः । इति । ब्रूयात् । न । अनुपऽसेचनः । इति । न । इदम् । च । किम् । च । इति ॥ २४ ॥

स प्रसिद्धो यो गुरुः उदीरितलक्षणस्य ओदनस्य महिमानम् माहात्म्यं विद्यात् जानीयात् असौ[1] उपदेशसमये अल्प इति न ब्रूयात् महिम्नोऽल्पत्वं नोपदिशेत् । अनुपसेचनः उपसिच्यते अनेनेति उपसेचनं क्षीराज्यदध्यादि तद्रहित इति च न ब्रूयात् । न च इदम् इति पुरोवर्तित्वेन निर्दिश्य ब्रूयात् । किम् इति अनिर्दिष्टरूपेण च[2] न ब्रूयात् । प्रागुक्तप्रकारेणैव सार्वात्म्यं ब्रूयाद् इत्यर्थः ॥

आधिक्यवचनमपि अस्य विषये[3] न युक्तम् इत्याह ॥

यावद् दाताभिमनस्येत तन्नाति वदेत् ॥ २५ ॥

यावत् । दाता । अभिऽमनस्येत । तत् । न । अति । वदेत् ॥ २५ ॥

दाता सवयज्ञानुष्ठाता यावत् फलम् अभिमनस्येत मनसा[4] अभिप्राप्तुम् इच्छेत् तत् नाति वदेत् । तत् फलम् अतिक्रम्य अधिकं न ब्रूयाद् इत्यर्थः ॥

अथ वक्ष्यमाणैः पर्यायैस्तस्यौदनस्य प्राशने भावनाविशेषं वक्तुं ब्रह्मवादिनां प्रश्नद्वयम् अवतारयति ॥

ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः[2] प्रत्यञ्चा३मिति[3] ॥ २६ ॥

ब्रह्मऽवादिनः । वदन्ति । पराञ्चम् । ओदनम् । प्र । आशी३ः[4] । प्रत्यञ्चा३म्[5] । इति ॥ २६ ॥

---

१ P विद्यात्. We with $\overset{2}{\text{P}}$ J Cp. २ V प्राशीर३ः. A B C R प्राशी३ः $\overset{m}{\text{S}}$ D प्राशीः. Cs प्राशीः. Dc प्राशीः changed to प्राशीः३. We with V. ३ A $\overset{h}{\text{B}}$ C D E K $\overset{m}{\text{K}}$ R $\overset{m}{\text{S}}$ P $\overset{2}{\text{P}}$ J Cp V Cs Dc all read : प्रत्यञ्चा३मिति. ४ $\overset{2}{\text{P}}$ प्र । आशीः ३ ।. P प्र । आशीः ।. J प्र । आशीः ३ ।. Cp प्र । आशीः ।. ५ P $\overset{2}{\text{P}}$ J प्रत्यंचाम् ३. We with Cp.

---

1 S′ असा—दश° for असौ उपदेश°. 2 S′ वचन for च न. 3 S′ विषयविशेषे for विषये which emendation is conjectural. 4 S′ doubtful between मनस्यभि° and मनसाभि°.

त्वमोदनं प्राशी३स्त्वामोदना३ इति ॥ २७ ॥

त्वम्। ओदनम्। प्र। आशी३ः। त्वाम्। ओदना३ः। इति ॥ २७ ॥

ब्रह्म वेदः तद् वदितुं शीलम् एषाम् इति ब्रह्मवा[दिनो ब्रह्म]विचारका महर्षयः। ते संभूय वदन्ति परस्परं भाषन्ते। हे देवदत्त त्वम् इमम् ओदनं पराञ्चम् पराङ्मुखं स्थितं प्राशीः प्राशितवान् असि उत प्रत्यञ्चम् आत्माभिमुखं स्थितं प्राशितवान् असि। प्राशितुस्तव प्राशितव्यः स ओदनः किं पराङ्मुखः उत अभिमुख इति प्रश्नः। "विचार्यमाणानाम्" इति प्लुतः॥ तथा हे देवदत्त त्वम् ओदनं प्राशीः भक्षितवान् असि अथ वा स एव ओदनस्त्वां प्राशीत् इति प्रश्नान्तरम्। अत्रापि पूर्ववत् प्लुतः॥

अत्र आद्ये प्रश्ने प्रथमकल्पे दोषम् आह ॥

पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥ २८ ॥

पराञ्चम्। च। एनम्। प्रऽआशीः। प्राणाः। त्वा। हास्यन्ति। इति। एनम्। आह ॥ २८ ॥

चशब्दश्चेदर्थे। पराञ्चम् पराङ्मुखत्वेन स्थितम् एनम् ओदनं प्राशीश्चेत् प्राणाः प्राणवायवः त्वा त्वां हास्यन्ति त्यक्ष्यन्तीत्येनं प्राशितारम् आह विद्वान् ब्रवीतु। बहिर्मुखः प्राणो बहिर्मुखौदनप्राशनाय शरीराद् विनिर्गतो भवेद् इत्यर्थः॥

द्वितीयकल्पम् अनूद्य दूषयति ॥

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥ २९ ॥

प्रत्यञ्चम्। च। एनम्। प्रऽआशीः। अपानाः। त्वा। हास्यन्ति। इति। एनम्। आह ॥ २९ ॥

---

१ Dc प्राशी३स्त्वा॰ corrected to प्राशी३स्त्वा॰. S̈ Cs प्राशीस्त्वा॰. A B C R K K̈ प्राशी३स्त्वा॰. P J प्र। आशीः ३।. P̈ प्र। आशीः ३।. Cp प्र। आशीः।. We with Dc P̈. २ P J ओदनाः ३।. P̈ Cp ओदनाः।. ३ P̈ एतम्. We with P J Cp.

---

1 S′ ॰मुख—मस्थि——वानसि.

अत्रापि चशब्दश्चेदर्थे । प्रतिमुखम् अवस्थितं चेद् एनम् ओदनं प्राशीस्तर्हि त्वा त्वाम् अपानाः अपानवायुवृत्तयो हास्यन्ति त्यक्ष्यन्ति । इत्येनं प्राशितारम् आह अभिज्ञो ब्रूयात् । अपानवायोरोदनस्य च[1] प्रत्यङ्मुखत्वेन अधोद्वारात् अपानस्य शरीराद् विनिर्गम एव स्याद् इत्यर्थः ॥

द्वितीयप्रश्नः अनङ्गीकारपरास्त इत्याह ॥

नैवाहमोदनं न मामोदनः ॥ ३० ॥

न । एव । अहम् । ओदनम् । न । माम् । ओदनः ॥ ३० ॥

अहम् ओदनं नैव प्राशिषम् । ओदनोपि मां न प्राशीत् । अतः पक्षद्वयस्यानङ्गीकारात् तत्प्रयुक्तदोषाभाव इत्यर्थः ॥

कथं तर्हि तत्प्राशनम् इति तत्राह ॥

ओदन एवौदनं प्राशीत् ॥ ३१ ॥ (८)

ओदनः । एव । ओदनम् । प्र । आशीत् ॥ ३१ ॥ (८)

भोक्तृभोक्तव्यप्रपञ्चात्मक ओदन[2] इति उक्तम् । अतः ओदन एव कर्ता ओदनं स्वात्मानं प्राशीत् प्राशितवान् । ⌛अश भोजने इत्यस्मात् लुङि रूपम्⌛ ॥

[इति] प्रथमसूक्तम् ॥

अथ उत्तरैः पर्यायैः ओदनस्यैव भोक्तृत्वं भोज्यत्वं च विपक्षे बाधपुरःसरं समर्थ्यते । तत्र प्रथमम् "तस्यौदनस्य बृहस्पतिः शिरः" इति यद् उक्तं विपक्षे बाधपुरःसरं तस्य प्रयोजनं प्रथमेन पर्यायेणाह ॥

(२) ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । बृहस्पतिना शीर्ष्णा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग

१ P P[2] J Cp प्र । आशीत् ।

1 S′ चा—योः for च. 2 S′ ओदनमिति.

एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १ ॥

ततः। च। एनम्। अन्येन। शीर्ष्णा। प्रऽआशीः। येन। च। एतम्। पूर्वे। ऋषयः। प्रऽआश्नन्॥ ज्येष्ठतः। ते। प्रऽजा। मरिष्यति। इति। एनम्। आह॥ तम्। वै। अहम्। न। अर्वाञ्चम्। न। पराञ्चम्। न। प्रत्यञ्चम्॥ बृहस्पतिना। शीर्ष्णा॥ तेन। एनम्। प्र। आशिषम्। तेन। एनम्। अजीगमम्॥ एषः। वै। ओदनः। सर्वऽअङ्गः। सर्वऽपरुः। सर्वऽतनूः॥ सर्वऽअङ्गः। एव। सर्वऽपरुः। सर्वऽतनूः। सम्। भवति। यः। एवम्। वेद॥ १॥

पूर्वे प्रथमभाविनोऽनुष्ठातार ऋषयः येन च शिरसा एतम् ओदनं प्राश्नन् प्राशितवन्तः। ॥अश भोजने। क्र्यादित्वात् श्नाप्रत्ययः॥। ततस्तस्माद् अन्येन शीर्ष्णा शिरसा। ॥"शीर्षंश्छन्दसि" इति शिरःशब्दस्य शीर्षन् आदेशः॥। ततश्चेति चशब्दश्चेदर्थे। अन्येन चेत् शिरसा एनम् उक्तप्रभावम् ओदनं प्राशीः हे देवदत्त प्राशितवान् असि ते तव प्रजा पुत्रादिरूपा ज्येष्ठत आरभ्य ज्येष्ठादिक्रमेण मरिष्यति इति अनेन प्रकारेण एनं प्राशितारम् आह अभिज्ञो ब्रूयात्। इत्थम् अयथाप्राशने दोष उपन्यस्तः। एतद्दोषपरिहारेण प्राशनम् आह तं वा इति। तं तथाविधम् ओदनम् अहम् अर्वाञ्चम् अवाङ्मुखम् अञ्चन्तं न प्राशिषम्। तथा पराञ्चम् पराङ्मुखम् अञ्चन्तमपि न प्राशिषम्। तथा प्रत्यञ्चम् आत्माभिमुखम् अञ्चन्तमपि न प्राशिषम्। अतः पराञ्चं चैनं प्राशीः इत्यादिना उक्तदोषस्य अप्रसङ्गः। कथं तर्हि प्राशीरित्याह। बृहस्पतिना शीर्ष्णा बृहस्पत्यात्मना ओदनसंबन्धिशिरसा। ऋषयो हि पूर्वम् अनेनैव शिरसा ओदनं प्राश्नन्। अहमपि ओदनात्मकस्तेनैव शिरसा एनम् ओदनं प्राशिषम् प्राशितवान् अस्मि। ओदन एवौदनं प्राशीत् इति ह्युक्तम्। तेनैव शिरसा एनम् ओदनम् अजीगमम् गन्तव्यं देशं प्रापितवान् अस्मि। ॥गमेर्ण्यन्तात् लुङि चङि रूपम्॥। एष वै इत्थं खलु प्राशितोऽयम् ओ-

दनः सर्वाङ्गः सर्वैरवयवैरुपेतः सर्वपरुः सर्वैः परुर्भिः पर्वभिः अवयवसंधिभिरुपेतः सर्वतनूः संपूर्णशरीरः । इत्थं वेदितुः फलम् आह सर्वाङ्ग एवेति । यः पुरुषः एवम् उक्तप्रकारेण ओदनस्य प्राशनं वेद जानाति सोपि सर्वाङ्गत्वादिफलं प्राप्तः सन् सं भवति पुण्यभूते स्वर्गादिलोके उत्पद्यते । एवम् उत्तरेपि पर्याया व्याख्येयाः ॥

"द्यावापृथिवी श्रोत्रे" इति द्यावापृथिव्योः ओदनसंबन्धिश्रोत्रत्वेन भावनं यद् उक्तं तत्प्रयोजनमपि विपक्षे बाधपुरःसरं द्वितीयमन्त्रेण उपन्यस्यति ॥

ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
बधिरो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न
प्रत्यञ्चम् । द्यावापृथिवीभ्यां श्रोत्राभ्याम् । ताभ्यामेनं प्राशिषं ता-
भ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ २ ॥

ततः । च । एनम् । अन्याभ्याम् । श्रोत्राभ्याम् । प्रऽआशीः । याभ्याम् । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ बधिरः । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ द्यावापृथिवीभ्याम् । श्रोत्राभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ २ ॥

एवम् अनुषज्य वाक्यं पूरयित्वा व्याख्येयम् । अयम् अर्थः । याभ्यां श्रोत्राभ्यां पूर्वे प्रथमभाविन ऋषयः एतम् ओदनं प्राश्नन् ततोऽन्याभ्यां श्रोत्राभ्यां लौकिकाभ्यां यदि ओदनं प्राशितवान् असि तर्हि त्वं बधिरः नष्टश्रोत्रेन्द्रियो भविष्यसि इत्येनं प्राशितारम् आह । तं वा अहम् इत्यादि पूर्ववत् । द्यावापृथिवीभ्यां श्रोत्राभ्याम् ओदनस्य श्रोत्रत्वेन भावि-

ताभ्या ताभ्यामेव एनम् ओदनं प्राशिषम् ताभ्यामेव एनम् [अजीगमम्] गमितवान् अस्मि न तु आत्मीयाभ्यां श्रोत्राभ्यां येन उक्तदोषः प्रसज्येद् इति भावः । एष वा ओदन इत्यादिवाक्यशेषः सर्वत्र समानार्थः । एवम् उत्तरेषु पर्यायेषु अनुषङ्गेण वाक्यपरिसमाप्तिर्वाक्ययोजना च कर्तव्या ॥

"सूर्याचन्द्रमसावक्षिणी" इति यद् उक्तं प्राक् तस्य प्रयोजनकथनपरस्तृतीयो मन्त्रः ॥

ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । अन्धो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । सूर्याचन्द्रम[1]साभ्यामक्षीभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ३ ॥

ततः । च । एनम् । अन्याभ्याम् । अक्षीभ्याम् । प्रऽआशीः । याभ्याम् । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ अन्धः । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सूर्याचन्द्रमसाभ्याम् । अक्षीभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ३ ॥

याभ्यां चक्षुर्भ्यां पूर्वे ऋषयः एतम् ओदनं प्राश्नन् ततश्च ताभ्यां चेद् अन्याभ्याम् अक्षीभ्यां चक्षुर्भ्याम् एनम् ओदनं प्राशितवान् असि [तर्हि] अयथाप्राशनात् अन्धः लुप्तचक्षुष्को भविष्यसि इत्येनं प्राशितारम् आह ब्रूयात् । ⧗अक्षीभ्याम् इति । "ई च द्विवचने" इति अक्षिशब्दस्य ईकारान्तादेशः⧗ । तं वा अहम् इत्यादि पूर्ववत् । सूर्याचन्द्रमसाभ्याम् सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ तद्रूपाभ्याम् अक्षीभ्याम् ओदनसंबन्धिच-

१ So we read with A B $\overset{h}{B}$ C D V E K $\overset{m}{K}$ R $\overset{m}{S}$ P $\overset{2}{P}$ J Cs Cp Dc.

क्षुभ्याम् । ताभ्याम् एनं प्राशिषम् इत्यादि पूर्ववत् । एष वा ओदनः सर्वाङ्ग इत्यादिवाक्यशेषः समानार्थः ॥

"ब्रह्म मुखम्" इति यद् ओदनस्य मुखकल्पनं कृतं तस्योपयोगम् आह ॥

ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । मुखतस्ते प्रजा मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । ब्रह्मणा मुखेन । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ४ ॥

ततः । च । एनम् । अन्येन । मुखेन । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ मुखतः । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ब्रह्मणा । मुखेन ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ४ ॥

येन च ओदनसंबन्धिना ब्रह्मात्मकेन मुखेन पूर्वे ऋषयः प्राश्नन् ततोन्येन चेन्मुखेन ओदनं प्राशीस्तर्हि मुखतः मुखाद् आरभ्य अभिमुखप्रदेशे वा ते त्वदीया प्रजा मरिष्यति विनङ्क्ष्यति इति अनेन प्रकारेण एनं प्राशितारम् आह कश्चिद् ब्रूयात् । तं वा अहम् इत्यादि पूर्ववत् । ब्रह्मणा यत् जगत्कारणं ब्रह्म वेदात्मकं वा तदात्मकेन मुखेन ओदनसंबन्धिना । तेन प्रागुक्तेन एनम् ओदनं प्राशिषम् इत्यादि समानम् ॥

पूर्वं "बृहस्पतिः शिरः" इत्यादिना कानिचिदेव अङ्गानि उपलक्षणत्वेन ओदनस्य परिकल्पितानि । अस्मिन् प्रकरणे अनुक्तानामपि अवयवानां

प्राशने करणत्वेन विनियोगादेव तत्तदवयवजातम् ओदनस्य अर्थात् क्लृप्तं वेदितव्यम्। तत्र अग्नेर्जिह्वैव[1] प्राशितुर्जिह्वेति पञ्चमेन मन्त्रेण प्रतिपादयति ॥

ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्। जिह्वा ते मरिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। अग्नेर्जिह्वया। तयैनं प्राशिषं तयैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ५ ॥

ततः। च। एनम्। अन्यया। जिह्वया। प्रऽआशीः। यया। च। एतम्। पूर्वे। ऋषयः। प्रऽआश्नन् ॥ जिह्वा। ते। मरिष्यति। इति। एनम्। आह ॥ तम्। वै। अहम्। न। अर्वाञ्चम्। न। पराञ्चम्। न। प्रत्यञ्चम् ॥ अग्नेः। जिह्वया ॥ तया। एनम्। प्र। आशिषम्। तया। एनम्। अजीगमम् ॥ एषः। वै। ओदनः। सर्वऽअङ्गः। सर्वऽपरुः। सर्वऽतनूः ॥ सर्वऽअङ्गः। एव। सर्वऽपरुः। सर्वऽतनूः। सम्। भवति। यः। एवम्। वेद ॥ ५ ॥

यया जिह्वया पूर्वं ऋषयः एतम् ओदनं प्राश्नन् ततोन्यया आत्मीयया जिह्वया चेत् हे देवदत्त त्वम् ओदनं प्राशीस्तर्हि ते त्वदीया जिह्वा मरिष्यति प्राणांस्त्यक्ष्यति। प्राणत्यागेन शुष्का स्वकार्यक्षमा न भविष्यतीत्यर्थः। ⌛मृङ् प्राणत्यागे। "म्रियतेर्लुङ्लिङोश्च" इति आत्मनेपदस्य नियमनात् परस्मैपदम्। "ऋद्धनोः स्ये" इति इडागमः⌛। तं वा अहम् इत्यादि पूर्ववत्। अग्नेः अवयवभूतया जिह्वया। सैव प्राशितुः ओदनस्य च जिह्वेत्यर्थः। तया जिह्वया एनम् ओदनम् अहं प्राशिषम् इत्यादि पूर्ववत् ॥

दन्तानामपि विपरिवृत्तिं षष्ठेन मन्त्रेण दर्शयति ॥

---

1 S′ omits व in जिह्वैव.

ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। दन्तास्ते शं- त्स्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ऋतुभिर्दन्तैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भ- वति य एवं वेद॥ ६॥

ततः। च। एनम्। अन्यैः। दन्तैः। प्रऽआशीः। यैः। च। एतम्। पूर्वे। ऋषयः। प्रऽआश्नन्॥ दन्ताः। ते। शत्स्यन्ति। इति। एनम्। आह॥ तम्। वै। अहम्। न। अर्वाञ्चम्। न। पराञ्चम्। न। प्रत्यञ्चम्॥ ऋतुऽभिः। दन्तैः॥ तैः। एनम्। प्र। आशिषम्। तैः। एनम्। अजीगमम्॥ एषः। वै। ओदनः। सर्वऽअङ्गः। स- र्वऽपरुः। सर्वऽतनूः॥ सर्वऽअङ्गः। एव। सर्वऽपरुः। सर्वऽतनूः। सम्। भवति। यः। एवम्। वेद॥ ६॥

यैर्दन्तैः एतम् ओदनं पूर्वे ऋषयः प्राश्नन् ततोऽन्यैर्दन्तैश्चेत् एनम् ओदनं प्राशीः प्राशितुस्ते तव दन्ताः शंत्स्यन्ति विशीर्णाः पतिष्यन्ति इ- ति अनेन प्रकारेण एनं प्राशितारम् आह अभिज्ञो ब्रूयात्। तं प्रति उत्तरं तं वा अहम् इत्यादि पूर्ववत्। ऋतुभिः वसन्तग्रीष्मादिभिर्दन्तैः। ऋतवः अस्य दन्ता इति अर्थाद् उक्तं भवति। तैः ऋत्वात्मकैर्दन्तैः ए- नम् ओदनं प्राशिषम् अतो नोक्तदोषप्रसङ्गः। अन्यद् उक्तार्थम्॥

"सप्तऋषयः प्राणापानाः" इति यत् प्राग् उक्तं तस्य इदानीम् उ- पयोगम् आह सप्तमेन मन्त्रेण॥

ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। प्रा- णापानास्त्वां हास्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं

---

१ B सत्स्यन्ती°. We with A B C D E K K R S P P J V Cs. २ B प्राशीर्यैश्चैतं. Cs प्राशीर्यैश्चैतं.

न प्रत्यञ्चम् । सप्तर्षिभिः प्राणापानैः । तैरेनं प्राशिषं तैरेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ७ ॥

ततः । च । एनम् । अन्यैः । प्राणापानैः । प्रऽआशीः । यैः । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ प्राणापानाः । त्वा । हास्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सप्तर्षिऽभिः । प्राणापानैः ॥ तैः । एनम् । प्र । आशिषम् । तैः । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ७ ॥

यैः प्राणापानैः ऋष्यात्मकैः एतम् ओदनं पूर्वेऽभिज्ञाः प्राश्नन् ततोऽन्यैश्चेत् प्राणापानैः एनम् ओदनं प्राशीस्तर्हि प्राशितारं त्वा त्वां प्राणापानाः प्राणापानात्मिका मुख्यप्राणस्य वृत्तयो हास्यन्ति त्यक्ष्यन्ति । ॥ ओहाक् त्यागे ॥ । इति अनेन प्रकारेण एनं प्राशितारम् आह विशेषज्ञो ब्रूयात् । तस्योत्तरं तं वा अहम् इत्यादि । सप्तऋषिभिः एतदात्मकैः प्राणापानैः । तैरेनं प्राशिषम् इत्यादि पूर्ववत् ॥

इत्थम् उत्तमाङ्गवर्तिनाम् अवयवानां प्राशने करणभूतानां देवतारूपत्वम् अभिधाय अन्येषाम् अवयवानां तथात्वम् अभिधित्सुः कृत्स्नशरीरव्यापिरूपस्य अन्तरिक्षरूपेण विपरिवृत्तिम् आह अष्टमेन पर्यायेण ॥

ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । अन्तरिक्षेण व्यचसा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव

१ B corrects सप्तऋषि° into सप्तर्षि°. Cs सप्तऋषि°. D K[m] S[m] सप्तऋषि°. We with A B[h] C E K R V. २ So P P[2] J. Cp सप्तऋषिऽभिः.

सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ८ ॥

ततः । च । एनम् । अन्येन । व्यचसा । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ राजऽयक्ष्मः । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अन्तरिक्षेण । व्यचसा[1] ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ८ ॥

येन व्यचसा व्याप्तिमता रूपेण कृत्स्नशरीरवर्तिना एतम् ओदनं पूर्वे ऋषयः प्राश्नन् ततोऽन्येन चेद् व्यचसा एनम् ओदनं प्राशीस्तर्हि त्वा त्वां प्राशितारं राजयक्ष्मः एतत्संज्ञः क्षयरोगो हनिष्यति मारयिष्यति । "ऋद्धनोः स्ये" इति इडागमः । यक्ष पूजायाम् इत्यस्मात् अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् [उ० १. १३७] इति औणादिको मन् प्रत्ययः । राज्ञः सोमस्य संबन्धी यक्ष्मो राजयक्ष्मः । श्रूयते हि तैत्तिरीयके । "राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म" इति [तै० सं० २. ५. ६. ५] । इति अनेन प्रकारेण एनं प्राशितारम् आह ब्रूयात् । तं वा अहम् इत्यादि पूर्ववत् ॥

[पृष्ठभागस्य द्युलोकरूपेण विपरिवृत्तिम् आह नवमेन मन्त्रेण ॥]

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । विद्युत् त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । दिवा पृष्ठेन । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ९ ॥

१ P व्यंचसा. We with P[2] J Cp.

1 S′ omits °वा°.

ततः । च । एनम् । अन्येन । पृष्ठेन । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ विऽद्युत् । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ दिवा । पृष्ठेन ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ९ ॥

[येन] दिवा द्युलोकात्मकेन पृष्ठेन मध्यशरीरापरभागेन एतम् ओदनं पूर्वं ऋषयः प्राश्नन् ततोऽन्येन चेत् पृष्ठेन आत्मीयेन शरीरापरभागेन त्वम् एनम् ओदनं प्राशीः विद्युत् विद्योतमाना अशनिस्त्वा त्वां हनिष्यति । इत्येनम् आह इत्यादि पूर्ववत् । दिवा द्युलोकात्मकेन पृष्ठेन शरीरापरभागेन । तेन अवयवेन एनं प्राशिषम् इत्यादि पूर्ववत् ॥

अवयवान्तरस्यापि देवतात्मकत्वं ब्रूते दशमेन मन्त्रेण ॥

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । कृष्या न रात्स्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । पृथिव्योरसा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १० ॥

ततः । च । एनम् । अन्येन । उरसा । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ कृष्या । न । रात्स्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ पृथिव्या । उरसा ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः ।

---

१ P[2] omits the avagraha. We with P J Cp.

सर्वंऽतनूः ॥ सर्वंऽअङ्गः । एव । सर्वंऽपरुः । सर्वंऽतनूः । सम् । भव-ति । यः । एवम् । वेद ॥ १० ॥

येन उरसा पूर्व ऋषयः प्राशितवन्तस्ततोऽन्येन चेद् उरसा स्तनमण्डलस्य उपरिवर्तिना पुरोभागस्थावयवेन त्वम् ओदनं प्राशीस्तर्हि कृष्या कर्षणक्रियया न रात्स्यसि । व्रीहियवादिसस्यैः समृद्धो न भविष्यसीत्यर्थः । ⌛राध साध संसिद्धौ । लृटि "एकाच उपदेशेनुदात्तात्" इति इट्प्रतिषेधः⌛ । अन्यद् उक्तार्थम् । पृथिव्या उरसा पृथिवीत्वेन भाव्यमानेन उरसा । तेनैनम् प्राशिषम् इत्यादि समानम् ॥

उदरस्यापि देवतात्मना भावनाम् आह एकादशेन मन्त्रेण ॥

ततश्चैनमन्येनोदरेण प्राशीर्येनं चैतं पूर्व ऋषयः प्राश्नन् । उदरदारस्त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । सत्येनोदरेण । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ११ ॥

ततः । च । एनम् । अन्येन । उदरेण । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ उदरऽदारः । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्येन । उदरेण ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ११ ॥

पूर्व ऋषयो येन उदरेण प्राश्नन् ततोऽन्येन उदरेण यदि इमम् ओदनं प्राशीस्तर्हि त्वा त्वाम् उदरदारः उदरस्य दरणात्मकः अतीसाराख्यो रोगो हनिष्यति मारयिष्यति । अन्यत् पूर्ववत् । सत्येन । यथार्थकथना-

त्मकं सत्यम् । तेन उदरेण तद्रूपतया भाव्यमानेन उदरेण । एनम् ओदनं प्राशिषम् इत्यादि समानम् ॥

अवयवान्तरस्यापि देवतारूपेण भावनम् आह द्वादशेन मन्त्रेण ॥

ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । अप्सु मरिष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । समुद्रेण वस्तिना । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १२ ॥

ततः । च । एनम् । अन्येन । वस्तिना । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ अप्ऽसु । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ समुद्रेण । वस्तिना ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ १२ ॥

वसति अस्मिन् अशितपीतान्नोदकम् [इति वस्तिः मूत्राशयः] । ✠इतरावयवानामिव तस्यापि प्राशने साधकतमत्वविवक्षया करणत्वम्✠ । येन वस्तिना पूर्वं ऋषयः प्राश्नन् ततोऽन्येन चेद् वस्तिना त्वम् ओदनं प्राशीस्तर्हि त्वम् अप्सु उदकेषु मरिष्यसि इति अनेन प्रकारेण एनं प्राशितारम् आह ब्रूयात् । तं वा अहम् इत्यादि उक्तार्थम् । समुद्रेण वस्तिना समुद्रात्मना भावितेन आत्मीयेन वस्तिना । तेनैनं प्राशिषम् इत्यादि पूर्ववत् । समुद्रस्य वस्तिरूपता तैत्तिरीयके समाम्नायते । "तद् "अभ्रमिव समहन्यत । तद् वस्तिम् अभिनत् । स समुद्रोभवत् । तस्मात् समुद्रस्य न पिबन्ति" इति [तै॰ब्रा॰२.२.९.३] ॥

ऊर्वोरपि देवताभावनाम् आह त्रयोदशेन मन्त्रेण ॥

ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्।
ऊरू ते मरिष्यत इत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न
प्रत्यञ्चम्। मित्रावरुणयोरूरुभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामे-
नमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। स-
र्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद॥ १३॥

ततः। च। एनम्। अन्याभ्याम्। ऊरुऽभ्याम्। प्रऽआशीः। याभ्याम्।
च। एतम्। पूर्वे। ऋषयः। प्रऽआश्नन्॥ ऊरू[1] इति। ते। मरिष्य-
तः। इति। एनम्। आह॥ तम्। वै। अहम्। न। अर्वाञ्चम्।
न। पराञ्चम्। न। प्रत्यञ्चम्॥ मित्रावरुणयोः। ऊरुऽभ्याम्॥ ता-
भ्याम्। एनम्। प्र। आशिषम्। ताभ्याम्। एनम्। अजीगमम्॥
एषः। वै। ओदनः। सर्वऽअङ्गः। सर्वऽपरुः। सर्वऽतनूः॥ सर्वऽअङ्गः।
एव। सर्वऽपरुः। सर्वऽतनूः। सम्। भवति। यः। एवम्। वेद॥ १३॥

याभ्याम् ऊरुभ्याम् पूर्वे ऋषयः प्राश्नन्। ॥ साधकतमत्वविवक्ष-
या करणत्वम् ॥। ततोऽन्याभ्यां चेद् ऊरुभ्याम् एनम् ओदनं प्रा-
शीः ते प्राशितुस्तव ऊरू मरिष्यतः त्यक्तप्राणौ शुष्कौ भविष्यत इत्येनम्
आह। तं वा अहम् इत्यादि पूर्ववत्। मित्रावरुणयोः मित्रश्च वरुण-
श्च मित्रावरुणौ। ॥ "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ्।
"देवताद्वन्द्वे च" इति उभयपदप्रकृतिस्वरत्वम् ॥। तयोः संबन्धि-
भ्याम् ऊरुभ्याम्। ताभ्याम् एनं प्राशिषम् इत्यादि पूर्ववद् योज्यम्॥

जानुनोरपि देवतासंबन्धित्वेन भावनम् आह [चतुर्दशेन मन्त्रेण]॥

ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्।
स्रामो भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्र-
त्यञ्चम्। त्वष्टुरष्ठीवद्भ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीग-
मम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव

---

१ P ऊरु.

सर्वंपरुः सर्वंतनूः सं भवति य एवं वेद ॥ १४ ॥

ततः । च । एनम् । अन्याभ्याम् । अष्ठीवत्ऽभ्याम् । प्रऽआशीः । याभ्याम् । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ स्रामः । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ त्वष्टुः । अष्ठीवत्ऽभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् वेद ॥ १४ ॥

अष्ठीवन्तौ अस्थिमन्तौ ऊर्वोरधःप्रदेशवर्तिनौ अवयवौ जानुलक्षणौ । ⌛"आसन्दीवद् अष्ठीवत्°" इति मतुपि निपात्यते⌛ । ताभ्याम् अष्ठीवद्भ्याम् अन्याभ्याम् इत्यादि सर्वं पूर्ववद् योज्यम् । स्रामः शुष्कजङ्घः । शुष्कजङ्घो भविष्यसि इत्येनं प्राशितारम् आह । तं वा अहम् इत्यादि पूर्ववत् ॥ त्वष्टुः देवस्य संबन्धिभ्याम् अष्ठीवद्भ्याम् ॥ गतार्थम् अन्यत् ॥

पादयोरपि देवतासंबन्धित्वेन भावनम् आह पञ्चदशेन मन्त्रेण ॥

ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
बहुचारी भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । अश्विनोः पादाभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १५ ॥

ततः । च । एनम् । अन्याभ्याम् । पादाभ्याम् । प्रऽआशीः । याभ्याम् । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ बहुऽचारी । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अश्विनोः । पादाभ्याम् ॥ ताभ्याम् । एनम् ।

१ B पदाभ्यां.

प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ १५ ॥

जङ्घयोरधोवर्तिनौ पादौ । बहुचारी बहु अधिकं चरितुं शीलम् अस्य स तथोक्तः । "सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः । सर्वदा प्रवासशील इत्यर्थः । अश्विनोः संबन्धिभ्यां तदीयत्वेन भाविताभ्यां पादाभ्याम् ॥ वाक्ययोजना पूर्ववत् ॥

पादाग्रयोरपि देवतासंबन्धित्वेन भावनम् आह ॥

> ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । सर्पस्त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । सवितुः प्रपदाभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १६ ॥

ततः । च । एनम् । अन्याभ्याम् । प्रऽपदाभ्याम् । प्रऽआशीः । याभ्याम् । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ सर्पः । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सवितुः । प्रऽपदाभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ १६ ॥

प्रपदाभ्यां पादाग्राभ्याम् । सर्पः प्रसिद्धः । सवितुः सर्वस्य प्रेरकस्य देवस्य संबन्धिभ्यां प्रपदाभ्यां पादाग्राभ्याम् ॥

हस्तयोरपि देवतासंबन्धित्वेन भावनम् आह ॥

---

१ K K^m V सवितुः. Cs सवितु प्र°.

ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न
प्रत्यञ्चम् । ऋतस्य हस्ताभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनम-
जीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग
एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १७ ॥

ततः । च । एनम् । अन्याभ्याम् । हस्ताभ्याम् । प्रऽआशीः । याभ्याम् ।
च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ ब्राह्मणम् । हनिष्यसि । इति ।
एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् ।
न । प्रत्यञ्चम् ॥ ऋतस्य । हस्ताभ्याम् ॥ ताभ्याम् । एनम् । प्र । आ-
शिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । स-
र्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः ।
सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ १७ ॥

ब्राह्मणं हनिष्यसीति । ब्रह्महत्या तव भविष्यतीत्यर्थः । ऋतं सत्यं परं ब्रह्म तस्य संबन्धिभ्यां हस्ताभ्याम् । ताभ्याम् एनम् इत्यादि अन्यत् सर्वं पूर्ववत् ॥

इत्थं प्राशितुः सर्वेष्वङ्गेषु देवताप्रतिपत्तीर्विधाय तदाधारभूतायां भूम्यामपि प्रतिपत्तिविशेषं विपक्षे बाधपुरःसरं दर्शयति ॥

ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् । अ-
प्रतिष्ठानो[1]ऽनायतनो मरिष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न
पराञ्चं न प्रत्यञ्चम् । सत्ये प्रतिष्ठाय । तयैनं प्राशिषं तयैनमजी-
गमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग ए-
व सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १८ ॥ (९)

ततः । च । एनम् । अन्यया । प्रतिऽस्थया[2] । प्रऽआशीः । यया । च ।

१ A B B[h] C R Cs °ष्ठानोनायतनो. We with D E S[m] V Dc. २ P °स्थाय. We with P[2] J Cp.

एतम् । पूर्वे । ऋषयः । प्रऽआश्नन्[1] ॥ अप्रतिऽस्थानः । अनायतनः । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्ये । प्रतिऽस्थाय ॥ तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ १८ ॥

प्रतितिष्ठति अस्याम् इति प्रतिष्ठा पादयोराधारभूता भूमिः । ⌛ष्ठा गतिनिवृत्तौ । "आतश्चोपसर्गे" इति अधिकरणे अङ् प्रत्ययः ⌛ । यया च प्रतिष्ठया सत्यब्रह्मात्मिकया एत[म् ओद]नं पूर्वे प्रथमभाविन ऋषयः प्राश्नन् ततोऽन्यया चेत् प्रतिष्ठया एनम् ओदनं प्राशीः प्राशितवान् असि तर्हि त्वम् अप्रतिष्ठानः प्रतिष्ठारहितः । तस्यैव अर्थकथनम् अनायतन इति । स्थानोपवे[शना]य भूमिरहितो भविष्यसि इत्येनं प्राशितारम् आह कश्चिद् विद्वान् ब्रूयात् । इति विपक्षे बाधोपन्यासः । तस्यैतद् उत्तरं तं वा अहम् इत्यादि । तं खलु उक्तप्रभावम् ओदनम् अहम् अ[र्वाञ्चम् अभि]मुखम् अवस्थितं न प्राशिषम् । न पराञ्चम् पराङ्मुखम् अवस्थितमपि न प्राशिषम् । न प्रत्यञ्चम् प्रत्यङ्मुखम् आभिमुख्येन अवस्थितमपि न प्राशिषम् । किं तु आत्मभूतम् ओदनं सत्ये सर्वदा बाधविधुरे "विज्ञानम् आनन्दं ब्रह्म" [बृ° आ° ३. ९. ३४] इत्याद्युपनिषदेकवेद्ये सर्वजगत्कल्पनास्पदे ब्रह्मणि प्रतिष्ठाय प्रतिष्ठितः समाश्रितो भूत्वा तेन सर्वजगत्प्रतिष्ठात्मकेन प्राशिषम् प्राशितवान् अस्मि । तेनैव सत्येन एनम् अजीगमम् उदरमध्यं गमितवान् अस्मि । यद्वा । अस्य सवयज्ञस्य फलभूतं नाकपृष्ठाख्यं लोकं गमितवान् अस्मि । एष खलु उदीरितभावनया प्राशित ओदनः सर्वाङ्गः सर्वैरङ्गैः अवयवैरुपेतः सर्वपरुः सर्वैः पर्वभिः अवयवसंधिभिरुपेतः सर्वतनूः कृत्स्नशरीरो भवति । सर्वशरीराभिमानिविराडात्मको भवतीत्यर्थः । उक्तम् अर्थं वेदितुः फलम् आह सर्वाङ्ग एवेत्यादिना ॥

---

१ P प्र । आश्नन्. J प्र । आश्नन् ।. P[2] प्रऽआश्नम् ।. We with Cp.

इत्थम् आद्यन्तयोः पर्याययोः संपूर्णाम्नानात् मध्यवर्तिषु पर्या[येषु अ-नु]षङ्गेण वाक्यपरिसमाप्तिं कृत्वा व्याख्यातव्यम्[1] ॥

[इति] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥

"एतद् वै ब्रध्नस्य विष्टपम्" इत्यस्य सूक्तस्य "तस्यौदनस्य" इति सूक्ते[न सह उक्तो] विनियोगः ॥

तत्र प्रथमा ॥

(३) ए॒तद् वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ॥ १ ॥

ए॒तत् । वै । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । यत् । ओ॒द॒नः ॥ १ ॥

यत् योऽयम् उक्तमहिमोपेत ओदनः एतत् खलु ब्रध्नस्य विष्टपम् ब-ध्नाति महिम्ना सर्वं जगत् सृजतीति ब्रध्नः सूर्यमण्डलमध्यवर्ती ईश्व-रः । ⧖ बन्धेर्ब्रधिबुधी च [उ॰ ३. ५] इति औणादिको नक् प्र-त्ययः प्रकृतेर्ब्रधादेशश्च ⧖ । तस्य विष्टपम् वियति विष्टब्धं मण्डलम् । सूर्यमण्डलात्मकोयम् ओदनं[2] इत्यर्थः ॥

एतद् वेदितुः फलम् आह द्वितीयया ॥

ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ ॥ २ ॥

ब्र॒ध्नऽलो॑कः । भ॒व॒ति॒ । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । श्र॒य॒ते॒ । यः । ए॒वम् । वेद॑ ॥ २ ॥

यः पुरुषः एवम् उक्तप्रकारेण [वेद ओदनस्य] सूर्यमण्डलात्मकत्वं वे-द । मण्डला[भिं[3]मानि]सूर्यरूपेण ओदनम् उपास्त इत्यर्थः । असौ ब्र-ध्नलोको भवति ब्रध्नस्य सूर्यस्य यो लोकस्तल्लोकवर्ती भवति । यद्वा सूर्य इव लोकनीयः दर्शनीयो भवति । ब्रध्नस्य सूर्यस्य विष्टपि विष्टब्धे मण्ड-लात्मके स्थाने श्रयते सेवते । सूर्यात्मको भवतीत्यर्थः । "असौ वा आ-दित्यो ब्रध्नस्य विष्टपम्" इति हि तैत्तिरीयकम् [तै॰ सं॰ ५. ३. ३. ५] ॥

अ[थ सू]र्यात्मकाद् ओदनात् सर्वेषां देवानां सृष्टिम् आह तृतीयया ॥

ए॒तस्मा॒द् वा ओ॑द॒नात् त्रय॑स्त्रिंशतं लो॒कान् निर॑मिमीत प्र॒जाप॑तिः ॥ ३ ॥

---

1 S′ व्याख्यातम्. 2 S′ ओदनम्. 3 S′ has in place of °भिमानि° a blank space for about three letters, followed by ति.

एतस्मात् । वै । ओदनात् । त्रयःऽत्रिंशतम् । लोकान् । निः । अमिमीत । प्रजाऽपतिः ॥ ३ ॥

एतस्मात् सूर्यात्मकाद् ओदनात् [सर्वजगदुपादान]भूतात् प्रजापतिः प्रजानां स्रष्टा देवः त्रयस्त्रिंशतं लोकान् "अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च" इति [ऐ° ब्रा° १.१०] ऐतरेयकादिश्रुतिप्रसिद्धा[1] ये त्रयस्त्रिंशत्संख्याका[1] देवास्तेषां लोकान् अधिष्ठातृसहितान् निरमिमीत निर्मितवान् ॥

तल्लोकप्राप्तिसाधनत्वेन यज्ञोपि अस्मादेव सूर्यात्मकाद् ओदनात् सृष्ट इत्याह ॥

तेषां प्रज्ञानाय यज्ञमसृजत ॥ ४ ॥

तेषाम् । प्रऽज्ञानाय । यज्ञम् । असृजत ॥ ४ ॥

तेषां देवलोकानां प्रज्ञानाय प्रकर्षेण ज्ञानाय तत्तल्लोकोपभोग्यसुखसाक्षात्काराय तत्साधनत्वेन इमं यज्ञम् असृजत सृष्टवान् । यज्ञसृष्ट्यभिधानादेव सर्वजगत्सृष्टिरुक्ता भवति । "अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत" [तै° सं° ७.१.१.२] इत्यादिश्रुतेः । स्मर्यते च । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति [म° स्मृ° ३.७६] ॥

इत्थं सर्वजगदुपादानभूतस्य ओदनस्य सूर्यमण्डलान्तर्वर्तिहिरण्यगर्भतादात्म्यं विदुषो माहात्म्यं दर्शयति ॥

स य एवं विदुष उपद्रष्टा भवति[१] प्राणं रुणद्धि ॥ ५ ॥

सः । यः । एवम् । विदुषः । उपऽद्रष्टा । भवति[१] । प्राणम् । रुणद्धि ॥ ५ ॥

स यः यः कश्चन पुरुषः एवम् उक्तप्रकारेण विदुषः उपासकस्य उपद्रष्टा भवति उप समीपे तत्कृतस्य अकामोपनतस्य द्रष्टा साक्षात्कर्ता भवति । तस्य मनसि उपरोधं जनयतीत्यर्थः । स उपरोधकः स्वशरीरे

१ So A B[h] C D E K K[m] R S[m] V Cs Dc. P P[2] J Cp भवति. See Rw.

1 S' प्रसिद्धः यत्र ---- संख्याका.

वर्तमानं प्राणं रुणद्धि आवृणोति निरुद्धगतिं करोति । प्राणोपासकस्य अनिष्टाचरणाद् इत्यर्थः ॥

न केवलम् एतावानेव दोषः सर्वफलहानिरपि तस्य स्याद् इत्याह ॥

न च॑ प्रा॒णं रु॒णद्धि सर्वज्या॒निं जी॑यते ॥ ६ ॥

न । च॒ । प्रा॒णम् । रु॒णद्धि । स॒र्व॒ऽज्या॒निम् । जी॒य॒ते॒ ॥ ६ ॥

प्राणं रुणद्धि इत्येतावदेव न च अपि तर्हि सर्वज्यानिम् प्रजापश्वादिरूपस्य सर्वस्य अभिमतस्य वस्तुनः ज्यानिर्हानिर्यथा भवति तथा जीयते हीयते निहीनो भवति । ज्या वयोहानौ । अस्मात् कर्मणि लट् । "ग्रहिज्या०" इत्यादिना संप्रसारणम् । जीयत इत्येतावता वयोहानिमात्रं गम्यते । हानेः सर्ववस्तुविषयताप्रतिपत्त्यर्थविशेषणसंबन्धाय ज्यानिं जीयत इति पुनरुक्तिः ॥

न केवलम् एतावदेव इत्याह ॥

न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रै॑नं ज॒रसः॑ प्रा॒णो ज॑हाति ॥ ७ ॥ (१०)

न । च॒ । स॒र्व॒ऽज्या॒निम् । जी॒यते॑ । पु॒रा । ए॒न॒म् । ज॒रसः॑ । प्रा॒णः । ज॒हाति॒ ॥ ७ ॥ (१०)

सर्वज्यानिं जीयत इति एतावदेव न च एनं निन्दकं जरसः जरावस्थायाः पुरा प्राणो जहाति परित्यजति । म्रियतेसावित्यर्थः । एतद् उक्तं भवति । विदुषो व्यतिक्रमं दृष्ट्वा निन्दतः पुरुषस्य प्रथमं प्राणरोधो भवति ततः सर्ववस्तुहानिर्भवति ततः अकालमरणम् इति ॥

[इति] तृतीयं सूक्तम् ॥

"प्राणाय नमः" इत्यादिसूक्तत्रयम् अर्थसूक्तम् । अनेन उपनयनकर्मणि माणवकस्य नाभिं संस्पृश्य आचार्यो जपेत् । "उपनयनम्" प्रक्रम्य सूत्रितम् । "दक्षिणेन पाणिना नाभिदेशं संस्तभ्य जपति आ र-
"भस्व[८, २] प्राणाय नमः[११, ६] विषासहिम्[१७, १] इत्यनुमन्त्र-
"यते" इति [कौ० ७, ६] ॥

तथा आयुष्कामः अनेनार्थसूक्तेन दक्षिणं कर्णम् अनुमन्त्रयेत ॥

तथा ऋषिहस्ते आयुष्कामस्य शरीरम् अभिमन्त्रयेत । सूत्रितं हि । "आ रभस्व[८, २] प्राणाय नमः[११, ६] विषासहिम्[१७, १] इत्य-"नुमन्त्रयते" इति [कौ० ७, ९]

तथा अस्यार्थसूक्तस्य आयुष्यगणे पाठाद् "विश्वकर्मभिरायुष्यैः स्वस्त्य-यनैराज्यं जुहुयात्" इति [होमे]षु विनियोगोऽनुसंधेयः [कौ० १४, ३] ॥

तथा "अमृतां दिव्यान्तरिक्षभौमेषु प्रयुञ्जीत" [न० क० १७] इति विहितायाम् अमृताख्यायां महाशान्तौ अनेनार्थसूक्तेन व्रीहियवमयं मणिं बध्नीयात् । तद् उक्तं नक्षत्रकल्पे । प्राणाय नम इति व्रीहियवम् अमृ-तायां बध्नीयात्" इति [न० क० १९] ॥

तथा ग्रहयज्ञे अनेनार्थसूक्तेन शनैश्चराय हविराज्यहोमं समिदाधानम् उपस्थानं वा कुर्यात् । तद् उक्तं शान्तिकल्पे । "सहस्रबाहुः पुरुषः "[१९, ६] केन पार्ष्णी[१०, २] प्राणाय नमः[११, ६] इति शनै-"श्चराय" इति [शा० क० १५] ॥

तथा शान्त्यर्थे लक्षहोमे एतद् अर्थसूक्तं होमे विनियुक्तं परिशिष्टे । "नमो देववधेभ्यः[६, १३] भवाशर्वौ[११, २] प्राणाय नमः[११, ६] इति हुत्वा" इति ॥

तत्र प्रथमा ॥

प्राणाय नमो यस्य सर्वमिदं वशे ।
यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥ १ ॥

प्राणाय । नमः । यस्य । सर्वम् । इदम् । वशे ।
यः । भूतः । सर्वस्य । ईश्वरः । यस्मिन् । सर्वम् । प्रतिऽस्थितम् ॥ १ ॥

प्राणाय प्रकर्षेण अनिति सर्वप्राणिशरीरं व्याप्य चेष्टत इति प्राणः समष्टिशरीराभिमानी प्रथमसृष्टो हिरण्यगर्भः । "प्राणः प्रजानाम् उद-यत्येष सूर्यः" इति [प्र० उ० १, ८] "स प्राणम् असृजत" इति [प्र० उ० ६, ४] "कस्मिन्नहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रति-

ष्ठिते प्रतिष्ठास्यामि[1]" [प्र॰ उ॰ ६. ३] इत्यादिश्रुतिभ्यः । तस्मै प्राणाय नमः नमस्कारोस्तु । ⧖"अनितेः" इति नकारस्य णत्वम्⧖ । तस्य सगुणब्रह्मात्मकत्वं दर्शयति । यस्य प्राणस्य वशे सर्वम् इदं चराचरात्मकं जगद् वर्तते । एतेन तस्य सकलजगन्नियन्तृत्वम् उक्तम् । यः प्राणो भूतः भूतकालावच्छिन्नः न तु भविष्यन् । सर्वदा लब्धसत्ताक इत्यर्थः । ⧖भू सत्तायाम् इत्यस्मात् कर्तरि निष्ठा⧖ । सर्वस्य प्राणिजातस्य ईश्वरः ईशिता कर्तुम् अकर्तुम् अन्यथा वा कर्तुं शक्तः । ⧖ईश ऐश्वर्ये । "स्थेशभासपिसकसो वरच्" इति वरच् प्रत्ययः । "स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च" इति षष्ठी⧖ । यस्मिन् उदीरितलक्षणे प्राणे परब्रह्मात्मके सर्वं समस्तं जगत् प्रतिष्ठितम् । कारणभूते तस्मिन् समवायवृत्त्या वर्तत इत्यर्थः । तस्मै प्राणाय नम इति संबन्धः ॥

द्वितीया ॥

नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥ २ ॥

नमः । ते । प्राण । क्रन्दाय । नमः । ते । स्तनयित्नवे ।
नमः । ते । प्राण । विऽद्युते । नमः । ते । प्राण । वर्षते ॥ २ ॥

हे प्राण क्रन्दाय क्रन्दनशीलाय ध्वनते [ते] तुभ्यं नमः । ⧖क्रदि आह्वाने रोदने च । इदित्त्वात् नुम् । पचाद्यच्⧖ । तथा स्तनयित्नवे मेघजालं प्रविश्य स्तनितं गर्जितं कुर्वते । ⧖स्तन शब्दे । अस्माण्ण्यन्ताद् औणादिक इत्नुच् प्रत्ययः । "अयामन्ताल्वाय्येत्न्विष्णुषु" इति णेः अय् आदेशः⧖ । एवंभूताय ते तुभ्यं नमः । हे प्राण विद्युते विद्युदात्मना विद्योतमानाय ते तुभ्यं नमः । तदनन्तरं वर्षते वृष्टिं कुर्वते ते तुभ्यम् हे प्राण नमोस्तु ॥

---

1 S′ inserts इति स प्राणमसृजत after प्रतिष्ठास्यामि, in forgetfulness that the S′ruti had already been quoted.

तृतीया ॥

यत् प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।
प्र वीयन्ते गर्भान् दधतेथो बह्वीर्वि जायन्ते ॥ ३ ॥

यत् । प्राणः । स्तनयित्नुना । अभिऽक्रन्दति । ओषधीः ।
प्र । वीयन्ते । गर्भान् । दधते[1] । अथो इति । बह्वीः । वि । जायन्ते ॥ ३ ॥

यत् यदा प्राणः जगत्प्राणभूतः सूर्यात्मको देवः स्तनयित्नुना मेघध्वनिना ओषधीः व्रीहियवाद्या ग्राम्याः आरण्याश्च वीरुधः अभिक्रन्दति अभिलक्ष्य शब्दायते । यथा गोयूथमध्ये दृप्तो वृषभः गर्भम् आधित्सुस्ता अभिलक्ष्य [शब्दं] करोति तथेत्यर्थः । तदा ता ओषधयः प्रवीयन्ते प्राणाभिक्रन्दनमात्रादेव गर्भं गृह्णन्ति । वी गतिप्रजनकान्त्यशनखादनेषु । वर्षर्तुः सर्वासाम् ओषधीनां गर्भग्रहणकाल इत्यर्थः । तदानीमेव गर्भान् दधते धारयन्ति । अथो अनन्तरमेव बह्वीः बह्वयो बहुप्रकारा वि जायन्ते विविधम् उत्पद्यन्ते ॥

चतुर्थी ॥

यत् प्राण ऋतावागतेभिक्रन्दत्योषधीः ।
सर्वं तदा प्र मोदते[2] यत् किं[3] च भूम्यामधि ॥ ४ ॥

यत् । प्राणः । ऋतौ । आऽगते । अभिऽक्रन्दति । ओषधीः ॥
सर्वम् । तदा । प्र । मोदते[4] । यत् । किम् । च । भूम्याम् । अधि ॥ ४ ॥

प्राणो देवः ऋतावागते ऋतुकाले समागते वर्षर्तौ आगते वा यत् यदा ओषधीः अभिक्रन्दति तदा सर्वं प्र मोदते प्रहृष्यति । मुद हर्षे । भूम्याम् अधि उपरि यत् किं च यत् किमपि प्राणिजातं वर्तते । तत् सर्वम् इत्यन्वयः ॥

---

१ P J द्धधते. We with P̊². २ B̊ʰ C मोदते. We with A D E K K̊ᵐ R S̊ᵐ V Dc. ३ So we with A B̊ʰ C D E K K̊ᵐ R S̊ᵐ P P̊² J V Dc Cp. See Rw. ४ P̊² J मोद्ते. We with P Cp.

पञ्चमी ॥

यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् ।
पशवस्तत् प्र मोदन्ते महो वै नो भविष्यति ॥ ५ ॥

यदा । प्राणः । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् ।
पशवः । तत् । प्र । मोदन्ते । महः । वै । नः । भविष्यति ॥ ५ ॥

यदा यस्मिन् काले प्राणो देवः महीम् महतीं पृथिवीम् विस्तीर्णां भूमिं वर्षेण वृष्टिकर्मणा अभ्यवर्षीत् अभितः सिक्तां करोति तत् तदानीं[1] पशवः गवाद्याः प्र मोदन्ते प्रहृष्यन्ति । केनाभिप्रायेणेत्याह । महो वै उत्सवः खलु नः अस्माकं भविष्यति । वृष्टेरनन्तरं पृथिव्यां भूयांसि सस्यानि उत्पद्यन्ते । तल्लक्षणेन अस्माकं पुष्टिर्भविष्यतीति प्रनृत्यन्तीत्यर्थः ॥

षष्ठी ॥

अभिवृष्टा[१] ओषधयः प्राणेन समवादिरन् ।
आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥ ६ ॥

अभिऽवृष्टाः । ओषधयः । प्राणेन । सम् । अवादिरन् ।
आयुः । वै । नः । प्र । अतीतरः । सर्वाः । नः । सुरभीः । अकः ॥६॥

प्राणेन देवेन अभिवृष्टाः अभिषिक्ता ओषधयो ग्राम्या आरण्याश्च तेनैव प्राणेन समवादिरन् समवदन्त संभाषणं कृतवत्यः । "भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः" इति आत्मनेपदम् । लङि व्यत्ययेन झस्य रन् आदेशः । तस्य "छन्दस्युभयथा" इति आर्धधातुकत्वाद् इडागमः । उपधावृद्धिश्छान्दसी । संवदनप्रकारमेव दर्शयति आयुरिति । हे प्राण नः अस्माकम् आयुः जीवनं त्वं प्रातीतरः प्रावर्धयः । प्रपूर्वस्तरतिर्वर्धनार्थः । अस्माण्ण्यन्तात् लुङि चङि रूपम् । तथा नः अस्मान् सर्वाः । "बहुवचनस्य वस्नसौ" इति द्वितीयान्तस्य अस्मदो नस् आदेशः । सुरभीः

१ B अभिवृष्ट्या. Sâyaṇa's text also अभिवृष्ट्या.

1 S' तदा followed by a space for two letters.

शोभनगन्धयुक्ता अकः अकार्षीः । ⌛डुकृञ् करणे । अस्माल्लुङि "मन्त्रे घस°" इति च्लेर्लुक् । "हल्ङ्याब्भ्यः°" इति तिलोपः⌛ ॥

सप्तमी ॥

नमस्ते अस्त्वायते नमो अस्तु परायते ।
नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥ ७ ॥

नमः । ते । अस्तु । आऽयते । नमः । अस्तु । पराऽयते ।
नमः । ते । प्राण । तिष्ठते । आसीनाय । उत । ते । नमः ॥ ७ ॥

हे प्राण आयते आगच्छते ते तुभ्यं नमोस्तु । तथा परायते पराङ्मुखं गच्छते तुभ्यं नमोस्तु । हे प्राण तिष्ठते यत्रक्वापि अवस्थिताय [ते] तुभ्यं नमोस्तु । आसीनाय उपविष्टाय ते तुभ्यं नमोस्तु । उतशब्दः अप्यर्थे । आगमनादिक्रियाः सर्वाः प्राणव्यापारनिर्वर्त्या इति तत्तदवस्थापन्नस्य नमस्कार्यत्वम् ॥

अष्टमी ॥

नमस्ते प्राण प्राणते नमो अस्त्वपानते ।
पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥ ८ ॥

नमः । ते । प्राण । प्राणते । नमः । अस्तु । अपानते ।
पराचीनाय । ते । नमः । प्रतीचीनाय । ते । नमः । सर्वस्मै । ते । इदम् ।
नमः ॥ ८ ॥

हे प्राण देव प्राणते प्राणनव्यापारं कुर्वते ते तुभ्यं नमोस्तु । तथा अपानते अपाननव्यापारं कुर्वते अपानवृत्त्यात्मकाय[1] तुभ्यं नमोस्तु । तथा पराचीनाय पराञ्चनाय परागमनस्वभावाय देहाद् बहिरवस्थिताय ते तुभ्यं नमोस्तु । तथा प्रतीचीनाय प्रतिमुखम् अञ्चते देहमध्ये वर्तमानाय

१ D S^m K omit अ° in अस्त्वायते. We with A B^h C E K K^m R Cs. २ B omits अ° in अस्तु. We with A B^h C D E K K^m R S^m V Cs.

1 S′ अपानावृत्त्या°.

ते तुभ्यं नमोस्तु । ॥ "विभाषाञ्चेरदिक्स्त्रियाम्" इति स्वार्थिकः खः ॥ । किं बहुना सर्वस्मै सर्वव्यापारकर्त्रे सर्वप्राणिशरीरान्तर्वर्तिने ते तुभ्यम् इदं नमः अयं नमस्कारो भवतु । ॥ "सर्वस्य सुपि" इति आद्युदात्तत्वम् ॥ ॥

नवमी ॥

या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी[1]।
अथो॒[2] यद् भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥ ९ ॥

या । ते॒ । प्रा॒ण॒ । प्रि॒या । त॒नूः । यो इति॑ । ते॒ । प्रा॒ण॒ । प्रेय॑सी ।
अथो॒ इति॑ । यत् । भे॒ष॒जम् । तव॑ । तस्य॑ । नः॒ । धे॒हि॒ । जी॒वसे॑ ॥ ९ ॥

हे प्राण ते तव या प्रिया प्रीतिविषया तनूः शरीरम् अस्ति तथा प्राण ते तव यौ* । ॥ लिङ्गव्यत्ययः ॥ । ये प्रेयसी प्रियतमरूपे प्राणापानवृत्तिद्वयात्मके अग्नीषोमरूपे वा । अथो अपि च तव संबन्धि यद् भेषजम् अमृतत्वप्रापकम् औषधम् अस्ति तस्य सर्वस्य प्रियतनुप्रभृतिकस्य सकाशात् नः अस्माकं जीवसे जीवनाय धेहि अमृतत्वसाधनम् औषधं प्रयच्छ ॥

दशमी ॥

प्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम् ।
प्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न ॥ १० ॥ (११)

प्रा॒णः । प्र॒ऽजाः । अनु॑ । व॒स्ते॒ । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ।
प्रा॒णः । ह॒ । सर्व॑स्य । ई॒श्व॒रः । यत् । च॒ । प्रा॒णति॑ । यत् । च॒ । न ॥१०॥ (११)

प्राणो देवः प्रजाः प्रजायमाना देवतिर्यङ्मनुष्याद्याः अनु वस्ते अनुक्रमेण च्छादयति । तच्छरीराणि नाडीद्वारा व्याप्य वर्तत इत्यर्थः । ॥ वस आच्छादने । अदादित्वात् शपो लुक् ॥ । तत्र दृष्टान्तः पिता पुत्रमिव । यथा पिता प्रियम् स्निग्धं पुत्रं वस्त्रेण स्वकीयेन आच्छादयति

१ B प्रेयंस्ति corrected from प्रेयंसी. Cs प्रेयंसि. २ B अथा॒.

तथेत्यर्थः । यच्च जङ्गमात्मकं वस्तु प्राणति प्राणनव्यापारं करोति यच्च स्थावरात्मकं न प्राणति प्राणनव्यापारं न करोति । किं तु आत्माविनाभूतः प्राणः स्थावरेषु निरुद्धगतिरेव अन्तर्वर्तते । तस्य सर्वस्य स्थावरजङ्गमात्मनो जगतः प्राणः खलु ईश्वरः ईशिता स्वामी ॥

[इति] चतुर्थं सूक्तम् ॥

"प्राणो मृत्युः" इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ॥

तत्र प्रथमा ॥

प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत् ॥ ११ ॥

प्राणः । मृत्युः । प्राणः । तक्मा । प्राणम् । देवाः । उप । आसते ।
प्राणः । ह । सत्यऽवादिनम् । उत्ऽतमे । लोके । आ । दधत् ॥ ११ ॥

प्राण एव देवो मृत्युः स्वनिर्गमनेन सर्वप्राणिनां मरणस्य कर्ता । स एव प्राणस्तक्मा कच्छ्रजीवनकरो ज्वरादिरोगः । तथा तं प्राणम् देहमध्यवर्तिनं देवाः इन्द्रियाणि उपासते । स्वस्वविषयोपभोगाय सेवन्त इत्यर्थः । यद्वा प्राणम् हिरण्यगर्भं समष्ट्यात्मकम् अग्न्यादयो देवा उपासते । स एव प्राणः सत्यवादिनम् । सत्यं यथार्थं वदितुं शीलम् अस्य स तथोक्तः । सत्यवदनशीलं महानुभावम् उत्तमे उत्कृष्टतमे लोके आ दधत् आदधाति स्थापयति ॥

द्वितीया ॥

प्राणो विराट् प्राणो देष्ट्री प्राणं सर्व उपासते ।
प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥ १२ ॥

प्राणः । विऽराट् । प्राणः । देष्ट्री । प्राणम् । सर्वे । उप । आसते ।
प्राणः । ह । सूर्यः । चन्द्रमाः । प्राणम् । आहुः । प्रजाऽपतिम् ॥ १२ ॥

प्राण एव देवो विराट् स्थूलप्रपञ्चाभिमानी ईश्वरः । तथा प्राणो दे-

१ B देव.

ष्ट्री स्वस्वव्यापारेषु सर्वेषां प्रेरयित्री परदेवता । तथाविधं प्राणं सर्वे जना उपासते स्वाभिलषितफलसिद्ध्यर्थं सेवन्ते । प्राण एव सूर्यः सर्वस्य प्रेरक आदित्यः । तथा चन्द्रमाः अमृतमयः सोमोपि स एव । एतेन प्राणस्य अग्नीषोमात्मकत्वम् उक्तम् । तथाविधमेव प्राणं प्रजापतिम् प्रजानां स्रष्टारं देवम् आहुः अभिज्ञाः कथयन्ति । "पत्यावैश्वर्ये" इति पूर्वपदप्रकृतिस्वरत्वम् ॥

तृतीया ॥

प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।
यवे ह प्राण आहितोपानो व्रीहिरुच्यते ॥ १३ ॥

प्राणापानौ । व्रीहिऽयवौ । अनड्वान् । प्राणः । उच्यते ।
यवे । ह । प्राणः । आऽहितः । अपानः । व्रीहिः । उच्यते ॥ १३ ॥

प्राणश्च अपानश्च प्राणापानौ मुख्यस्य प्राणस्य प्रधानभूतौ वृत्तिविशेषौ । तावेव व्रीहिश्च यवश्च व्रीहियवौ । प्राणापानात्मकौ तावित्यर्थः । यो वृत्तिमान् मुख्यः प्राणः सः अनड्वान् उच्यते । व्रीहियवयोः कर्षणेन उत्पादयिता बलीवर्दो वृत्तिमत्प्राणात्मना ज्ञातव्य इत्यर्थः । उक्तमेवार्थं विवृणोति । यवे ह यवे खलु प्राणः प्राणवृत्त्यात्मको वायुः आहितः स्रष्ट्रा स्थापितः । अपानवृत्त्यात्मकस्तु वायुः व्रीहिरुच्यते । व्रीहिषु अवस्थानेन तदात्मकः कथ्यत इत्यर्थः । अत एव तौ व्रीहियवौ ओषधीषु मध्ये पुष्टिकरत्वेन सर्वप्राणिभिरुपजीव्यौ । अतो लोकरक्षणाय प्राण एव व्रीहियवानडुद्रूपेण कथ्यत इत्यर्थः ॥

चतुर्थी ॥

अपानति प्राणति पुरुषो गर्भे अन्तरा ।
यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥ १४ ॥

अप । अनति । प्र । अनति । पुरुषः । गर्भे । अन्तरा ।
यदा । त्वम् । प्राण । जिन्वसि । अथ । सः । जायते । पुनः ॥ १४ ॥

अन्नात्मकत्वं[1] प्राणस्य उक्तम् । तद्रसपरिणामरूपशरीरधारी पुरुषो गर्भे स्त्रिया गर्भाशये अन्तरा मध्ये अपानति हे प्राण त्वत्प्रवेशेन अपाननव्यापारं करोति [प्राणति प्राणनव्यापारं करोति] च । हे प्राण शुक्लशोणितावस्थायामेव[2] पुरुषशरीरं प्रविश्य तत्परिणामाय प्राणापानवृत्ती जनयसीत्यर्थः । हे प्राण त्वं यदा यस्मिन् काले जिन्वसि गर्भीभूतं पुरुषं मातृभुक्ताहारपरिणतान्नरसेन प्रीणयसि । पुष्यसीत्यर्थः[3] । ⌛ जिवि प्रीणने । इदित्वात् नुम् ⌛ । अथो[4]* अनन्तरमेव स पुरुषः पुनर्जायते स्वार्जितपरिपक्वपुण्यपापफलोपभोगाय पुनर्भूम्याम् उत्पद्यते । प्राण एव सर्वस्योत्पादक इत्यर्थः ॥

पञ्चमी ॥

प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥ १५ ॥

प्राणम् । आहुः । मातरिश्वानम् । वातः । ह । प्राणः । उच्यते ।
प्राणे । ह । भूतम् । भव्यम् । च । प्राणे । सर्वम् । प्रतिऽस्थितम् ॥१५॥

मातरि । अन्तरिक्षे श्वसिति वर्तत इति मातरिश्वा अन्तरिक्षाधिपतिर्वायुः । तं वायुं प्राणं प्राणात्मकम् आहुः । "वायुः प्राणो भूत्वा नासिके प्राविशत्" इति श्रुतेः[5] [ऐ॰आ॰२.४.२] । उक्त एवार्थो व्यतिहारेण दृढीक्रियते वातो ह प्राण उच्यत इति । "सैषानस्तमिता देवता यद् वायुः" [बृ॰आ॰१.३.३३] इति सर्वजगदाधारभूतः सूत्रात्मा यो वातः सदा गमनशीलो वायुः स एव प्राण उच्यते । अतो नानयोर्भेद इत्यर्थः । तस्मिन् प्राणे जगदाधारभूते सूत्रात्मनि भूतम् भूतकालावच्छिन्नम् उत्पन्नं जगत् भव्यम् भविष्यत्कालावच्छिन्नम् उत्पत्स्यमानं जगत् । तद् उभयम् आश्रित्य वर्तते । किं बहुना तस्मिन् प्राणे सर्वम् इदं जगत् प्रतिष्ठितम् आश्रितम् ॥

1 S' अनात्मकत्वं for अन्नात्मकत्वं. 2 S' शुक्र°. 3 S' पुष्यती°. 4 Sâyaṇa's text also: जिन्वस्यथो स &c. 5 S' ¯तः for श्रुतेः.

षष्ठी ॥

आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत।
ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥ १६ ॥

आथर्वणीः। आङ्गिरसीः। दैवीः। मनुष्यऽजाः। उत।
ओषधयः। प्र। जायन्ते। यदा। त्वम्। प्राण। जिन्वसि ॥ १६ ॥

आथर्वणीः अथर्वणा महर्षिणा सृष्टा आङ्गिरसीः अङ्गिरोभिः सृष्टाः। उभयत्र "तस्येदम्"-अर्थे अण्। दैवीः देवैः सृष्टाः। "देवाद् यञञौ" इति प्राग्दीव्यतीयः अञ् प्रत्ययः। सर्वत्र "टिड्ढाणञ्°" इति ङीप्। "वा छन्दसि" इति जसि पूर्वसवर्णदीर्घः। मनुष्यजाः मनुष्येभ्य उत्पन्नाः। उतशब्दः अप्यर्थे। एवं नानाविधा ओषधयः प्र जायन्ते प्रकर्षेण उत्पद्यन्ते हे प्राण त्वं यदा यस्मिन् काले जिन्वसि वृष्टिप्रदानेन प्रीणयसि ॥

सप्तमी ॥

यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम्।
ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥ १७ ॥

यदा। प्राणः। अभिऽअवर्षीत्। वर्षेण। पृथिवीम्। महीम्।
ओषधयः। प्र। जायन्ते। अथो इति। याः। काः। च। वीरुधः ॥१७॥

पूर्वोर्धर्चो व्याख्यातः। ओषधयो व्रीहियवाद्याः वृष्ट्यनन्तरमेव प्र जायन्ते। अथो अपि च याः काश्च वीरुधः विरोहणशीला लतारूपा आरण्याः ता अपि सर्वाः प्र जायन्ते ॥

अष्टमी ॥

यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः।
सर्वे तस्मै बलिं हरानमुष्मिँल्लोक उत्तमे ॥ १८ ॥

---

१ B अथर्व°. २ P अथर्वणीः. We with P J Cp. ३ V B B C K Cs. जायन्ते°. We with A D E K R S.

यः । ते । प्राण । इदम् । वेद । यस्मिन् । च । असि । प्रतिऽस्थितः ।
सर्वे । तस्मै । बलिम् । हरान् । अमुष्मिन् । लोके । उत्ऽतमे ॥ १८ ॥

हे प्राण ते त्वदीयम् इदम् उदितं माहात्म्यं यो वेद जानाति यस्मिंश्च विदुषि त्वं प्रतिष्ठितोसि उदीरितमहिमोपेतत्वेन भाव्यमानो भवसि तस्मै विदुषे सर्वे देवाः अमुष्मिन् स्वर्गे उत्तमे उत्कृष्टतमे लोके बलिम् अमृतमयं भागं हरान् हरन्ति । ॥ हरतेर्लेटि आडागमः । "इतश्च लोपः०" इति इकारलोपः । संयोगान्तलोपः ॥ ॥

नवमी ॥

यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।
एवा तस्मै बलिं हरान् यस्त्वा शृणवत् सुश्रवः ॥ १९ ॥

यथा । प्राण । बलिऽहृतः । तुभ्यम् । सर्वाः । प्रऽजाः । इमाः ।
एव । तस्मै । बलिम् । हरान् । यः । त्वा । शृणवत् । सुऽश्रवः ॥ १९ ॥

हे प्राण सर्वा इमाः प्रजाः देवतिर्यङ्मनुष्याद्याः यथा येन प्रकारेण तुभ्यं त्वदर्थं बलिहृतः बलेर्भोक्तव्यस्य अन्नस्य हर्तारः उपहर्तारो भवन्ति एव एवं तस्मै विदुषे बलिं हरान् हरन्तु प्रयच्छन्तु । हे शुंश्रुवः[*] शृण्वन् प्राण त्वा त्वां यः शृणवत् शृणुयात् तव माहात्म्यप्रतिपादकं मन्त्रजातं श्रवणेन्द्रियेण जानीयात् । तस्मै इति संबन्धः । ॥ शृणवत् इति । श्रु श्रवणे । अस्मात् लेटि अडागमः । "श्रुवः शृ च" इति श्नुप्रत्ययः शृभावश्च । शुंश्रुव[*] इति । तस्मादेव धातोर्लिटः क्वसुः ॥ ॥

दशमी ॥

अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।
स भूतो भव्यं भविष्यत् पिता पुत्रं प्र विवेशा[२] शचीभिः ॥ २० ॥ (१२)

अन्तः । गर्भः । चरति । देवतासु । आऽभूतः । भूतः । सः । ऊं इति ।
जायते । पुनः ।

---

२ K $\overset{m}{K}$ V विवेश. We with A $\overset{h}{B}$ C D E R $\overset{m}{S}$ Cs.

---

1 S' सर्वविदुषे.

सः। भूतः। भव्यम्। भविष्यत्। पिता। पुत्रम्। प्र। विवेश। शचीभिः ॥ २० ॥ (१२)

देवतासु देवेषु अन्तः मध्ये गर्भः सन् प्राणश्चरति। न केवलं मनुष्यादिष्वित्यर्थः। आभूतः आसमन्ताद् व्याप्तो भूतः नित्यः सन् स उ स एव प्राणः पुनर्जायते। तत्तच्छरीरेण सह पुनरुत्पद्यत इवेत्यर्थः। भूतः नित्यवर्तमानः स प्राणः भूतम् भूतकालावच्छिन्नं वस्तु भविष्यत् भाविकालावच्छिन्नम् उत्पत्स्यमानं च वस्तु शचीभिः आत्मीयाभिः शक्तिभिः प्र विवेश। पिता पुत्रम्। लुप्तोपमम् एतत्। यथा पिता स्वकीयं पुत्रं स्वावयवैरनुप्रविशति तथेत्यर्थः। अथ वा प्राण एव हि सर्वस्य लोकस्य पिता जनकः। सोयं पुत्रम् स्वस्माद् उत्पन्नं पुत्रभूतं सर्वं जगत् सात्मकं कर्तुं प्रविवेशेत्यर्थः ॥

[इति] पञ्चमं सूक्तम् ॥

"एकं पादम्" इति सूक्तस्यापि पूर्ववद् विनियोगः ॥

तत्र प्रथमा ॥

एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन्।
यदङ्ग स तमुत्खिदेन्नैवाद्य न श्वः स्या-
न्न रात्री नाहः[1] स्यान्न व्युच्छेत् कदा चन ॥ २१ ॥

एकम्। पादम्। न। उत्। खिदति। सलिलात्। हंसः। उत्ऽचरन्[2]।
यत्। अङ्ग। सः। तम्। उत्ऽखिदेत्। न। एव। अद्य। न। श्वः। स्यात्।
न। रात्री। न। अहः। स्यात्। न। वि। उच्छेत्। कदा।
चन ॥ २१ ॥

हन्ति गच्छतीति हंसः जगत्प्राणभूतः सूर्यः। स सलिलाद् उच्चरन् उद्गच्छन्। उद्यन्नित्यर्थः। एकं पादं नोत्खिदति नोद्धरति। एकं पादं निश्चलं स्थापयित्वा एकेनैव पादेन परिभ्रमतीत्यर्थः। तथा च मन्त्रव-

१ A B D E K $\overset{m}{K}$ R $\overset{m}{S}$ V Cs नाहं स्या॰. We with $\overset{h}{B}$ C. २ P ॰चरंत्.

र्णः । "तं सूर्यं देवम् अजम् एकपादम्" इति [तै॰ब्रा॰ ३.१.२.८]। अङ्ग हे देवदत्त स उच्चरन् सूर्यः यत् यदि तं निहितं पादम् उत्खिदेत् क्षिपेत् तर्हि असौ द्वाभ्यां पादाभ्याम् अस्मदादिवद् यत्रक्वापि गच्छेत् निषीदेद् वा । तथा च कालपरिच्छेदकस्य सूर्यस्य[1] परिस्पन्दाभावात् अद्य श्वः रात्री अहः इत्येवं विभिन्नव्यवहारो न स्यात् । "रात्रेश्चाजसौ" इति रात्रिशब्दात् ङीप् । कदा चन कदाचिदपि न व्युच्छेत् । व्युच्छनम् उषसः प्रादुर्भावः । सूर्यस्योदयेऽसंभाव्यमाने तत्पुरोभाविनी उषा अपि नोदियात्[2] । तथा च जगदान्ध्यमेव स्याद् इत्यर्थः ॥ अथ वा हन्ति गच्छति कृत्स्नशरीरं व्याप्य वर्तत इति हंसः प्राणः । सलिलात् सलिलोपलक्षितात् पाञ्चभौतिकाद् देहाद् उच्चरन् प्राणवृत्त्यात्मना ऊर्ध्वं गच्छन् एकं पादम् अपानवृत्त्यात्मकं नोत्खिदति नोत्क्षिपति । यदि स प्राणस्तमपि अपानात्मकं पादम् उत्खिदेत् शरीराद् उत्क्षिपेत् तदा प्राणस्य कार्त्स्न्येन[3] शरीरतो निर्गतत्वात् मृतशरीरस्य तस्य अद्य श्वः रात्रिः अहः इत्येवमात्मकः कालविभागो न स्यात् । कदाचिदपि न व्युच्छेत् तमसो निवृत्तिर्न स्यात् । अतः जगत् सजीवं कर्तुम् एकं पादं नोत्खिदतीत्यर्थः ॥

द्वितीया ॥

अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा[१] ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥ २२ ॥

अष्टाऽचक्रम् । वर्तते । एकऽनेमि । सहस्रऽअक्षरम् । प्र । पुरः । नि । पश्चा[२] ।
अर्धेन । विश्वम् । भुवनम् । जजान । यत् । अस्य । अर्धम् । कतमः । सः ।
केतुः ॥ २२ ॥

अष्टाचक्रम् त्वगसृगाद्याः सप्त धातवः ओजो नाम अष्टमो धातुः । ते-

---

१ V K पश्चात्. We with A B B^h C D E K^m R S^m V Cs. २ P^2 पश्चात्. Cp पश्चात् corrected into पश्चा. We with P J.

---

1 S′ सूर्यपरिस्प°. 2 S′ उषा अप्युदियात्. 3 S′ omit °न शरीरतो.

त्र रथात्मना वर्णनीयस्य शरीरस्य चक्रत्वेन रूप्यन्ते । अष्टौ चक्राणि यस्य तद् अष्टाचक्रं शरीरम् । ⧖"छन्दसि च" इति अष्टनो दीर्घः⧖ । ताहृक् शरीरम् एकनेमि एकेनैव प्राणेन नेमिनेव वेष्टितम् । लोके हि रथचक्रं नेमिवेष्टितमेव प्रवर्तते। अत्र तु चक्राष्टकमपि एक एव प्राणात्मको नेमिः आवेष्ट्य वर्तयतीत्यर्थः । सहस्राक्षरम् बहुभिरक्षैरुपेतम् । ⧖रो मत्वर्थीयः⧖ । यद्वा प्राणपरिस्पन्दवशेन सहस्रं बहुविधानि अक्षराणि वर्णावर्णात्मकानि शब्दरूपाणि यस्य तत् तथोक्तम् । यद्वा । ⧖अश्नोतेः औणादिकः [सर]प्रत्ययः⧖ । बहुविधव्याप्तिकम् इत्यर्थः । एवंरथात्मकं शरीरं पुरः पुरस्तात् पूर्वस्मिन् भागे प्र वर्तते पश्चा*त् अपरभागे नि वर्तते । इत्थंमहानुभावः प्राणः प्राणिशरीरं प्रविश्य तत्र [प्रवृत्ति]निवृत्ती जनयतीत्यर्थः । शरीरस्य रथत्वेन रूपणम् अन्यत्रापि आम्नातम् ।

आत्मानं रथिनं विद्धि शरीरं रथमेव तु [क° व° ३. ३]

इत्यादिना । स प्राणः सूत्रात्मभावेन स्थितः अर्धेन स्वात्मनोंशेन एकेन विश्वम् सर्वं भुवनम् भूतजातं जजान प्राणवाय्वात्मना प्रविश्य जनयामास । अस्य सूत्रात्मनः प्राणस्य यद् अन्यद् अर्धम् प्राणरूपेणावस्थिताद् अपरो भागः तस्यापरिच्छिन्नस्य केतुः कतमः कीदृशः । परब्रह्मात्मकस्य प्राणस्य एकदेश एव कृत्स्नं जगद् वर्तते । अवशिष्टं स्वरूपम् आनन्त्याद् इदम् ईदृग् इति निर्धारयितुम् अशक्यम् इत्यर्थः । श्रूयते हि । "पादोऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि" इति [ऋ° १०. ९०. ३] । स्मृतिश्च भवति ।

विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्। इति [भ° गी° १०. ४२]॥

तृतीया ॥

यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः ।
अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑स्तु ते ॥ २३ ॥

यः । अ॒स्य । वि॒श्वऽज॑न्मनः । ईशे॑ । विश्व॑स्य । चेष्ट॑तः ।
अन्ये॑षु । क्षि॒प्रऽध॑न्वने । तस्मै॑ । प्रा॒ण॒ । नम॑ः । अ॒स्तु॒ । ते॒ ॥ २३ ॥

यः प्राणो विश्वजन्मनः विश्वानि सर्वाणि नानारूपाणि जन्मानि यस्य तत् तथोक्तम् तस्य चेष्टतः व्याप्रियमाणस्य अस्य विश्वस्य [सर्व]स्य जगतः ईशे ईष्टे । ईश ऐश्वर्ये । "लोपस्त आत्मनेपदेषु" इति तलोपः । अन्येषु प्राणिशरीरेषु क्षिप्रधन्वने क्षिप्रं गच्छते व्याप्नुवते । धविर्गत्यर्थः । इदित्त्वात् नुम् । कनिन् युवृषितक्षि[राजि]धन्वीत्यादिना [उ॰ १. १५४] कनिन् प्रत्ययः । हे प्राण तस्मै तथाविधाय ते तुभ्यं नमोस्तु ॥

चतुर्थी ॥

यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।
अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥ २४ ॥
यः । अस्य । सर्वऽजन्मनः । ईशे । सर्वस्य । चेष्टतः ।
अतन्द्रः । ब्रह्मणा । धीरः । प्राणः । मा । अनु । तिष्ठतु ॥ २४ ॥

पूर्वोर्धर्चो व्याख्यातः । विश्वशब्दस्य स्थाने सर्वशब्द एव विशेषः । स जगदीश्वरः प्राणः अतन्द्रः आलस्यरहितः सर्वदा सर्वत्र संचरिष्णुः[1] धीरः धिया ज्ञानशक्त्या युक्तः ब्रह्मणा सर्वगतब्रह्मात्मकेन अनवच्छिन्नेन रूपेण मा माम् अनु तिष्ठतु अनुवर्तताम् ॥

पञ्चमी ॥

ऊर्ध्वः सुप्तेषु जागार[1] ननु तिर्यङ् नि पद्यते ।
न सुप्तमस्य सुप्तेष्वनु शुश्राव[2] कश्चन ॥ २५ ॥
ऊर्ध्वः । सुप्तेषु । जागार । ननु । तिर्यङ् । नि । पद्यते ।
न । सुप्तम् । अस्य । सुप्तेषु । अनु । शुश्राव[3] । कः । चन ॥ २५ ॥

हे प्राण त्वम् ऊर्ध्वः उत्थितः सन् सुप्तेषु निद्रापरवशेषु प्राणिषु जागर[2*] जागृहि तद्रक्षणार्थं निद्रारहितो वर्तस्व । जागृ निद्राक्षये ।

१ **V K** जागर. **C**s जागार् नतु. We with **A B B^h C D E K^m R V.** २ **D S^m C**s सुश्राव. We with **A B B^h C E K K^m R V.** ३ **P J P^2** सुश्राव ।. We with **C**p.

1 **S′** omit °चरिष्णुः धीरः. 2 So in **S′**. Sâyaṇa's text also is जागर.

लोटि "बहुलं छन्दसि" इति शपो लुगभावः । जागरणे कारणम् आह नन्विति । सुप्तः प्राणी तिर्यङ् तिर्यगवस्थितः नि पद्यते निद्रापरवशः शेते । ननु इति प्रश्ने । अतस्त्वं जागृहीत्यर्थः । प्राणस्यापि सुप्तिः किं न स्याद् इति तत्राह न सुप्तम् इति । प्राणिषु सुप्तेषु निद्रापरवशेषु सत्सु तच्छरीरमध्यवर्तिनः अस्य प्राणस्य सुप्तम् स्वापं कश्चन कोपि पुरुषः न अनु शुश्राव अनु पारंपर्यक्रमेण श्रुतवान् । प्राणस्वपनस्य वक्ता श्रोता च दुर्लभ इत्यर्थः ॥

षष्ठी ॥

प्राण मा मत् पर्यावृतो न मदन्यो भविष्यसि ।
अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥ २६ ॥ (१३)

प्राण । मा । मत् । परिऽआवृतः । न । मत् । अन्यः । भविष्यसि ।
अपाम् । गर्भम्ऽइव । जीवसे । प्राण । बध्नामि । त्वा । मयि ॥ २६ ॥ (१३)

हे प्राण मत् सकाशात् मा पर्यावृतः पराङ्मुखो मा भूः । वृतु वर्तने । अस्मात् माङि लुङि "द्युद्भ्यो लुङि" इति परस्मैपदम् । "पुषादिद्युताद्यॢदितः॰" इति च्लेः अङ् आदेशः । पर्यावृत्त्यसंभवम् आह । हे प्राण त्वं मत् सकाशाद् अन्यो न भविष्यसि मया सह तादात्म्यापन्न एव वर्तसे । अतः पर्यावृत्तिशङ्कापि न संभवतीत्यर्थः । अतो हे प्राण त्वा त्वां मयि मच्छरीरे जीवसे जीवनाय बध्नामि आसजामि । अपां गर्भमिव अपाम् उदकानां गर्भभूतं वैश्वानराग्निं जीवनार्थं देहमध्ये धारयन्ति तथेत्यर्थः । अग्नेः अब्गर्भत्वं मन्त्रवर्णाद् अवगम्यते । "अपां गर्भं दर्शतम् ओषधीनाम्" [ऋ॰१.१६४.५२] "अग्ने[1] विश्वस्य भूतस्याग्ने गर्भो अपामसि" इति [तै॰सं॰४.२.३.३] च ॥

षष्ठं सूक्तम् ॥

---

१ A B[h] C D E K[m] R S[m] मंत् पर्या॰ and मंदन्यो respectively. We with B K P[2] V Cs.
२ P J मत्॰ । Cp मत् । changed into मत् ।. We with P[2]. ३ J मत् ।. Cp मत् । changed into मत् ।. We with P P[2].

---

1 So S′.

इति सायणार्यविरचिते अथर्वसंहिताभाष्ये
एकादशकाण्डे द्वितीयोनुवाकः ॥

तृतीयेनुवाके पञ्च सूक्तानि । तत्र "ब्रह्मचारीष्णंश्चरति" इत्यादिभिस्त्रिभिः सूक्तैर्ब्रह्मचारिणो माहात्म्यम् उच्यते । तस्य ब्रह्मयज्ञजपे[1] विनियोगः ॥

तत्र प्रथमसूक्ते प्रथमा ॥

ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
स दाधार पृथिवीं दिवं च स आचार्यं[1] तपसा पिपर्ति ॥ १ ॥

ब्रह्मऽचारी । इष्णन् । चरति । रोदसी इति । उभे इति । तस्मिन् । देवाः ।
समऽमनसः । भवन्ति ।
सः । दाधार । पृथिवीम् । दिवम् । च । सः । आऽचार्यम् । तपसा ।
पिपर्ति ॥ १ ॥

ब्रह्मचारी ब्रह्मणि वेदात्मके अध्येतव्ये चरितुं[2] शीलम् अस्य स तथोक्तः उभे रोदसी द्यावापृथिव्यौ इष्णन् आत्मीयेन तपसा अभीक्ष्णं व्याप्नुवन् चरति स्वनियमे प्रवर्तते । इष आभीक्ष्ण्ये । अस्मात् लटः शत्रादेशः । क्र्यादित्वात् श्ना प्रत्ययः । तस्मिन् ब्रह्मचारिणि सर्वे इन्द्रादयो देवाः संमनसः समानमनस्का भवन्ति । अनुग्रहबुद्धियुक्ता भवन्तीत्यर्थः । स ब्रह्मचारी आत्मीयेन तपसा पृथिवीम् भूमिं दिवम् द्युलोकं च दाधार । तुजादित्वाद् अभ्यासदीर्घत्वम् । धारयति पोषयति । तथा आचार्यम् स्वं गुरुं तेनैव तपसा पिपर्ति पालयति । सन्मार्गवृत्त्या आचार्यं परिपालयतीत्यर्थः । "शिष्यपापं गुरोरपि" इति शिष्यकृतेन पापेन गुरोरपि पातित्यस्मरणाद् एवम् उक्तम् । "चरे[3]राङि चागुरौ" इति [गुरावभि]धेये आङ्पूर्वाच्चरतेः "ऋहलोर्ण्यत्"

१ A B B[h] C D E K[m] R S[m] Cs २ for १. We with K V.

1 S′ °जप° for °जपे. 2 S′ वेति followed by a blank space for two or three letters after चरितुं. 3 S′ has आङि for चरेराङि.

इति ण्यदेव प्रत्ययो भवति । "तित् स्वरितः" इति स्वरितत्वम् । पिपर्तीति । पॄ पालनपूरणयोः । जुहोत्यादित्वात् शपः श्लुः । "अर्तिपिपर्त्योश्च" इति अभ्यासस्य इत्त्वम् ॥

द्वितीया ॥

ब्रह्मचारिणं पितरो देवजनाः पृथग् देवा अनुसंयन्ति सर्वे ।
गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत् त्रिशताः षट्सहस्राः[१] सर्वान्त्स देवांस्तपसा पिपर्ति ॥ २ ॥

ब्रह्मऽचारिणम् । पितरः । देवऽजनाः । पृथक् । देवाः । अनुऽसंयन्ति । सर्वे । गन्धर्वाः । एनम् । अनु । आयन् । त्रयःऽत्रिंशत् । त्रिऽशताः । षट्ऽसहस्राः । सर्वान् । सः । देवान् । तपसा । पिपर्ति ॥ २ ॥

ब्रह्मचारिणम् ब्रह्मचर्य[म् आचर]न्तं पुरुषं पितरः पितृगणा देवजनाः एतत्संज्ञा देवगणा अन्ये च सर्वे देवा इन्द्रादयः पृथग् अनुसंयन्ति । तस्य रक्षणार्थं पृथक् पृथक् तम् अनुगच्छन्तीत्यर्थः । तथा गन्धर्वाः अन्तरिक्षसंचारिणो विश्वावसुप्रभृतयः एनं ब्रह्मचारिणम् अन्वायन् अनुगच्छन्ति । ये च त्रयस्त्रिंशद् देवाः "अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च" [ऐ॰ ब्रा॰ १. १०] इत्येवं प्राग् उदाहृताः ये च त्रिशताः । त्रय इति अत्रापि संबध्यते । त्र्युत्तरत्रिशतसंख्याकास्तद्विभूतिरूपा देवाः । तथा षट्सहस्राः ये च तद्विभूतिरूपाः षट्सहस्रसंख्याका देवाः । एवमेव वैश्वदेवनिविदि देवानां संख्या उत्तरोत्तरं भूयसी तन्माहात्म्यप्रतिपादनाय समाम्नायते । "ये स्थ त्रय एकादशास्त्रयश्च त्रिंशच्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा" इति प्रक्रम्य "अतो वा देवा भूयांसः स्थ" इति [निवि॰ १. ७] । तत्र प्रकृतसंख्यातो भूयस्त्वश्रवणाद् अत्र षट्सहस्रा इति अधिकसंख्योक्तिः । तान् सर्वान् देवान् स ब्रह्मचारी तपसा आत्मीयेन ब्रह्मचर्यनियमेन पिपर्ति पालयति । देवमनुष्यादिरूपं सर्वं जगद् ब्रह्मचर्येण ध्रियत इत्यर्थः ॥

---

१ B omits the visarga. We with A B^h C D E K K^m R S^m V Cs.

तृतीया ॥

आचार्य॑ उपनय॑मानो ब्रह्मचारिणं॑ कृणुते गर्भ॑मन्तः ।
तं रात्री॑स्तिस्र उदरे॑ बिभर्ति तं जातं द्रष्टु॑मभिसंय॑न्ति देवाः ॥ ३ ॥

आऽचार्यः॑ । उपऽनय॑मानः । ब्रह्मऽचारिण॑म् । कृणुते । गर्भ॑म् । अन्तः ।
तम् । रात्रीः॑ । तिस्रः । उदरे॑ । बिभर्ति । तम् । जातम् । द्रष्टु॑म् । अभिऽ-
संय॑न्ति । देवाः ॥ ३ ॥

ब्रह्मचारिणम् माणवकम् उपनयमानः स्वसमीपम् उपगमयन् आचार्यः अन्तः विद्याशरीरस्य मध्ये गर्भं कृणुते करोति । ✻उपनयमान इति । "संमाननोत्संजनाचार्यकरण°" इति आत्मनेपदम्✻ । तं गर्भीभूतं ब्रह्मचारिणं तिस्रो रात्रीः । ✻"°अत्यन्तसंयोगे" द्वितीया✻ । तावत्कालपर्यन्तं त्रिरात्रम् उदरे आत्मीये बिभर्ति धारयति । चतुर्थे दिवसे जातम् विद्यामयशरीराद् उत्पन्नं तं ब्रह्मचारिणं द्रष्टुम् अवलोकयितुं देवा अभिसंयन्ति अभिमुखं संभूय गच्छन्ति । उपनयनसंस्कारेण माणवकस्य आचार्यसकाशाद् उत्पत्तिं भगवान् आपस्तम्बोपि आह स्म । "स हि विद्यातस्तं जनयति । तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः" इति आप° ध° १. १. १५-१७ ॥

चतुर्थी ॥

इयं समित् पृथिवी द्यौर्द्वितीयोतान्तरि॑क्षं समिधा॑ पृणाति ।
ब्रह्मचारी समिधा मेख॑लया श्रमे॑ण लोकांस्तप॑सा पिपर्ति ॥ ४ ॥

इय॑म्[1] । सम्ऽइत् । पृथिवी । द्यौः । द्वितीया॑ । उत । अन्तरि॑क्षम् । सम्ऽइ-
धा॑ । पृणाति ।
ब्रह्मऽचारी । सम्ऽइधा॑ । मेख॑लया । श्रमे॑ण । लोकान् । तप॑सा । पिप-
र्ति ॥ ४ ॥

पूर्वं ब्रह्मचारिणो माहात्म्यकथनपुरःसरं तदुत्पत्तिरभिहिता । अधुना

१ P इदम्. We with P[2] J Cp.

स्तुतिव्याजेन तन्नियमा उपदिश्यन्ते । इयं परिदृश्यमाना पृथिवी ब्रह्मचारिणः प्रथमा समित् । द्यौः द्युलोकात्मिका द्वितीया समित् । उत अपि च अन्तरिक्षे* द्यावापृथिव्योर्मध्ये समिधा अग्नावाधीयमानया पृणाति पूरयति । ※ पृ पालनपूरणयोः । "प्वादीनां ह्रस्वः" इति ह्रस्वत्वम् ※ । इत्थं ब्रह्मचारी समिधा आधीयमान[1]या मेखल[2]या धार्यमाणया मौञ्ज्या श्रमेण इन्द्रियनिग्रहोद्भूतखेदेन तपसा अन्येनापि देहसंतापकेन नियमजातेन लोकान् प्रागुक्तान् पृथिव्यादीन् पिपर्ति पूरयति पालयति वा । अतः समिदाधानादिकम् अवश्यम् अस्य कर्तव्यम् इत्यर्थः ॥

पञ्चमी ॥

पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥ ५ ॥

पूर्वः । जातः । ब्रह्मणः । ब्रह्मऽचारी । घर्मम् । वसानः । तपसा । उत् । अतिष्ठत् ।
तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवाः । च । सर्वे । अमृतेन । साकम् ॥ ५ ॥

यत् सर्वजगत्कारणं ब्रह्म सत्यज्ञानादिलक्षणं तस्माद् ब्रह्मणः सकाशाद् ब्रह्मचारी पूर्वो जातः प्रथमम् उत्पन्नः । स च उत्पन्नो घर्मम् दीप्तं रूपं वसानः आच्छादयन् तपसा समिदाधानादिरूपेण सह उदतिष्ठत् उत्थितवान् । तस्मात् ब्रह्मचार्यात्मना तपस्तप्यमानाद् ब्रह्मणः सकाशाद् ब्राह्मणम् ब्राह्मणानां स्वभूतं ज्येष्ठम् प्रशस्यतमं वृद्धतमं वा ब्रह्म वेदात्मकं जातम् प्रादुर्भूतम् । तत्प्रतिपाद्याः सर्वे अग्न्यादयो देवाश्च अमृतेन अमृतत्वप्रापकेन स्वोपभोग्येन साकं सह । जाता इत्यर्थः । प्रथमजननाद् ब्रह्मचारी सर्वश्रेष्ठ इत्यर्थः ॥

1 S' आधीयमानाया. 2 S' मेखलाया.

षष्ठी ॥

ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत् ॥ ६ ॥

ब्रह्मऽचारी । एति । सम्ऽइधा । सम्ऽइद्धः । कार्ष्णम् । वसानः । दीक्षितः । दीर्घऽश्मश्रुः ।
सः । सद्यः । एति । पूर्वस्मात् । उत्तरम् । समुद्रम् । लोकान् । सम्ऽगृभ्य । मुहुः । आऽचरिक्रत् ॥ ६ ॥

समिधा सायंप्रातरग्नावाधीयमानया तज्जनितेन तेजसा समिद्धः संदीपितः कार्ष्णम् कृष्णमृगसंबन्धि अजिनं वसानः धारयन् दीक्षितः भिक्षाचरणादिभिर्नियमविशेषैर्नियन्त्रितः दीर्घश्मश्रुः दीर्घैरायतैः श्मश्रुभिर्युक्तः सन् ब्रह्मचारी ब्रह्मचर्यधर्मेण युक्तः एति वर्तते । स उदीरितलक्षणो ब्रह्मचारी सद्यः शीघ्रं पूर्वस्मात् समुद्रात् उत्तरम् उत्तरदिगवस्थितं समुद्रम् एति गच्छति । तपसो महिम्ना व्याप्नोतीत्यर्थः । तथा लोकान् पृथिव्यन्तरिक्षादीन् संगृह्य[2] हस्ते धृत्वा मुहुः अत्यर्थम् आचरिक्रत् आभिमुख्येन करोति । सर्वे लोका अस्य वशे भवन्तीत्यर्थः । आचरिक्रत् इति । करोतेर्यङ्लुगन्तात् लङि रूपम् ॥

सप्तमी ॥

ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥ ७ ॥

ब्रह्मऽचारी । जनयन् । ब्रह्म । अपः । लोकम् । प्रजाऽपतिम् । परमेऽस्थिनम् । विऽराजम् ।

१ B दीर्घः श्मश्रुः. २ P कर्ष्णम् ।. We with P̊ J Cp. ३ P °चरिकृत् ।. We with P̊ J Cp. ४ B D R S̊ K̊ K Cs भूत्वाअमृत°. We with A B̊ C E V. ५ P लोकाम् ।. We with P̊ J Cp.

1 S′ has space for six letters after °श्मश्रुः and omits दीर्घैरा° from the following word. 2 Sâyaṇa's text in S′ too: संगृह्य.

गर्भः । भूत्वा । अमृतस्य । योनौ । इन्द्रः । ह । भूत्वा । असुरान् । तत्तर्ह ॥ ७ ॥

उक्तलक्षणो ब्रह्मचारी ब्रह्मचर्यमहिम्ना ब्रह्म ब्राह्मणजातिम् अपः स्नानपानार्था गङ्गाद्या नदीः इमम् आत्मनः फलभूतं स्वर्गादिलोकं प्रजापतिम् प्रजानां स्रष्टारम् अवान्तरसृष्टिकरं परमेष्ठिनम् परमे उत्कृष्टे सत्यलोके तिष्ठतीति परमेष्ठी तम् आदिब्रह्माणं विराजम् स्थूलप्रपञ्चशरीराभिमानिनम् ईश्वरं च जनयन् उत्पादयन्[1] वर्तते । स्वस्वकारणाद् उत्पद्यमानानाम् एषां ब्रह्मचर्यं निमित्तकारणम् इति तदाश्रयभूतो ब्रह्मचार्येव जनयन्निति उपचर्यते । अमृतस्य अमरणशीलस्य ब्रह्मणः संबन्धिन्यां योनौ सत्त्वरजस्तमोगुणात्मिकायां प्रकृतौ प्रथमं ब्रह्मचारी गर्भो भूत्वा उदीरितं सर्वं जनयति । पश्चात् इन्द्रो ह भूत्वा तपोबलाद् इन्द्रत्वं प्राप्य असुरान् सुरविरोधिनो दैत्यान् ततर्ह जघान । ॥ तृह हिंसि हिंसायाम् ॥ । इत्थं सर्वजगत्कर्तृत्वेन ब्रह्मचारिणः स्तुतिः ॥

अष्टमी ॥

आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
ते[1] रक्षति[2] तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥ ८ ॥

आऽचार्यः । ततक्ष । नभसी इति । उभे इति । इमे इति । उर्वी इति । गम्भीरे इति । पृथिवीम् । दिवम् । च ।
ते इति । रक्षति । तपसा । ब्रह्मऽचारी । तस्मिन् । देवाः । सम्ऽमनसः । भवन्ति ॥ ८ ॥

इमे परिदृश्यमाने उभे नभसी नभः अन्तरिक्षम् । तत्साहचर्याद् द्विवचनेन पृथिव्युपलक्ष्यते । द्यावापृथिव्यौ आचार्यस्ततक्ष तक्षणेन जनयामास । ॥ तक्षू त्वक्षू तनूकरणे । अस्मात् लिट् ॥ । नभसी विशेष्येते । उर्वी विस्तीर्णे गम्भीरे गाम्भीर्ययुक्ते । परिच्छेत्तुम् अशक्ये

१ K V तं. We with A B B^h C D E K^m R S^m V Cs. २ B^h रक्षन्तु.

1 S' उत्पाद्य°.

इत्यर्थः । ते एव व्यस्तं निर्दिशति पृथिवीं दिवं चेति । *तं द्यावापृथिव्योरुत्पादकम् आचार्यं ब्रह्मचारी आत्मीयेन तपसा ब्रह्मचर्यनियमेन रक्षति पालयति । तस्मिंस्तथाविधे ब्रह्मचारिणि सर्वे देवाः संमनसः समानमनस्काः प्रीता भवन्ति ॥

नवमी ॥

इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥ ९ ॥

इमाम् । भूमिम् । पृथिवीम् । ब्रह्मऽचारी । भिक्षाम् । आ । जभार । प्रथमः । दिवम् । च ।

ते इति । कृत्वा । सम्ऽइधौ । उप । आस्ते । तयोः । आर्पिता । भुवनानि । विश्वा ॥ ९ ॥

इमां परिदृश्यमानां पृथिवीम् प्रथितां विस्तीर्णां भूमिं ब्रह्मचारी प्रथमः प्रथमभावी सन् भिक्षाम् आ जभार भिक्षात्वेन आहृतवान् । अनन्तरं दिवम् द्युलोकं च द्वितीयां भिक्षाम् आजहार । ⌛ "हृग्रहोर्भः०" इति भत्वम् ⌛ । ते द्यावापृथिव्यौ भिक्षणेन लब्धे समिधौ कृत्वा उपास्ते अग्निं परिचरति । समिन्धनसाधनयोस्तयोर्द्यावापृथिव्योः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आर्पिता अर्पितानि स्थापितानि । आश्रित्य वर्तन्त इत्यर्थः ॥

दशमी ॥

अर्वागन्यः परो अन्यो दिवस्पृष्ठाद् गुहा निधी निहितौ ब्राह्मणस्य ।
तौ रक्षति तपसा ब्रह्मचारी तत् केवलं कृणुते ब्रह्म विद्वान् ॥ १० ॥ (१४)

अर्वाक् । अन्यः । परः । अन्यः । दिवः । पृष्ठात् । गुहा । निधी इति निऽधी । निऽहितौ । ब्राह्मणस्य ।

तौ । रक्षति । तपसा । ब्रह्मऽचारी । तत् । केवलम् । कृणुते । ब्रह्म । विद्वान् ॥ १० ॥ (१४)

दिवः द्युलोकस्य पृष्ठात् उपरिभागाद् अर्वाक् अधः भूलोके अन्यः एको निधिर्वेदात्मकः गुहा गुहायाम् आचार्यहृदयरूपायां निक्षिप्तः। अन्यः अपरो निधिस्तत्प्रतिपाद्यदेवतारूपः परः परस्ताद् उपरि देशे गुहायां ज्ञातुम् अशक्ये स्थाने निक्षिप्तः। ब्राह्मणस्य अधीतवेदस्य संबन्धिनौ तौ निहितौ निक्षिप्तौ निधी ब्रह्मचारी तपसा ब्रह्मचर्यनियमेन रक्षति पालयति। विद्वान् वेदार्थरहस्याभिज्ञः तत् शब्दतदर्थात्मकं निधिद्वयं केवलम् निष्प्रपञ्चं ब्रह्म कृणुते कुरुते। स्वात्मभूते परब्रह्मणि वेदराशेस्तदर्थस्य च अध्यस्तत्वेन अधिष्ठानभूतं ब्रह्मैव तादृूप्येण साक्षात्करोतीत्यर्थः॥

[इति] तृतीयेनुवाके प्रथमं सूक्तम्॥

द्वितीयसूक्ते प्रथमा॥

अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे।
तयोः श्रयन्ते रश्मयोधि दृढास्ताना तिष्ठति तपसा ब्रह्मचारी॥ ११॥

अर्वाक्। अन्यः। इतः। अन्यः। पृथिव्याः। अग्नी इति। सम्ऽएतः। नभसी इति। अन्तरा। इमे इति।
तयोः। श्रयन्ते। रश्मयः। अधि। दृढाः। तान्। आ। तिष्ठति। तपसा। ब्रह्मऽचारी॥ ११॥

इतः अस्याः पृथिव्या अर्वाक् अधःप्रदेशे अन्यः एकोग्निः अनुद्यत्सूर्यात्मको वर्तते। अन्यः अपरः पार्थिवोऽग्निः पृथिव्या उपरि वर्तते। ततः सूर्ये उदिते सति इमे नभसी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये तावग्नी समेतः परस्परं संगतौ भवतः। ⌛“अन्तरान्तरेणयुक्ते” इति द्वितीया⌛। तयोः सूर्याग्न्योः संबन्धिनो रश्मयः परस्परसंमेलनेन अति*दृढाः श्रयन्ते द्यावापृथिव्यौ आश्रयन्ति। “वैश्वानरो यतते सूर्येण” इति हि [ऋ॰ १. ९८. १] निगमः। इत्थम् अग्निद्वयोपेतां *तां भूमिं ब्रह्मचारी तपसा तपोमहिम्ना आ तिष्ठति अधितिष्ठति। अग्निरूपेण तस्या अधिदेवता भवतीत्यर्थः॥

द्वितीया ॥

अभिक्रन्दन् स्तनयन्नरुणः शितिङ्गो बृहच्छेपोनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥

अभिऽक्रन्दन् । स्तनयन् । अरुणः । शितिङ्गः । बृहत् । शेपः । अनु । भूमौ । जभार ।

ब्रह्मऽचारी । सिञ्चति । सानौ । रेतः । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिशः । चतस्रः ॥ १२ ॥

अभिक्रन्दन् अभितः शब्दं कुर्वन् । एतदेव विव्रियते । स्तनयन् मेघेषु स्तनितं गर्जितं कुर्वन् श्यंतिङ्गः श्येतवर्णे जलपूर्णे मेघं प्राप्तः एवंभूतो वरुणः बृहत् प्रभूतं शेपः आत्मीयं प्रजननं भूमौ पृथिव्याम् अनु जभार जहार । तेन वरुणसंबन्धिना शेपसा ब्रह्मचारी स्वतपोमहिम्ना सर्वजगदुत्पादकम् उदकलक्षणं वरुणसंबन्धि रेतः पृथिव्यां सानौ उन्नतप्रदेशे सिञ्चति वर्षति । एतेन सर्वजगदुत्पादनार्थम् ऊर्ध्वरेतस्कत्वं ब्रह्मचारिणः सूचितं भवति । वारुणमेव रेतः सिञ्चति न स्वकीयम् इत्यर्थस्य अवगमात् । तेन वृष्टेन उदकलक्षणेन रेतसा प्रदिशश्चतस्रः प्राच्याद्या महादिशो जीवन्ति प्राणान् धारयन्ति । तत्रत्याः प्राणिनः समृद्धा भवन्तीत्यर्थः । यस्मिन् राष्ट्रे ब्रह्मचारी निवसति तत्र कालवृष्टिर्भवतीति तात्पर्यार्थः ॥

तृतीया ॥

अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्य१प्सु समिधमा दधाति ।
तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥ १३ ॥

१ K K̆ B̆ A C V °क्रन्दं for °क्रन्दन्. We with D E R S̆. २ Cs स्तनयंन्वरुणः. ३ K V श्यन्तिङ्गो, a maladoption of Sâyaṇa's reading taken from his text which reads श्यंतिगो. K V, while preserving °तिङ्गो of the MSS; adopted श्यन्° from Sâyaṇa's text, and thus made up a new reading of their own. ४ So P P̆ J Cp. ५ P जीवन्ती ।. We with P̆ J Cp. ६ A B B̆ C D E S̆ ३ for १. We with K K̆ V Cs.

अग्नौ । सूर्ये । चन्द्रमसि । मातरिश्वन् । ब्रह्मऽचारी । अप्ऽसु । समऽइ-धम् । आ । दधाति ।

तासाम् । अर्चींषि । पृथक् । अभ्रे । चरन्ति । तासाम् । आज्यम् । पुरुषः । वर्षम् । आपः ॥ १३ ॥

ब्रह्मचारी ब्रह्मचर्यनियमवान् पुरुषः अग्नौ पृथिव्यामवस्थिते अन्तरिक्षगते सूर्ये चन्द्रमसि मातरिश्वन् मातरिश्वनि वायौ अप्सु च समिधम् आ दधाति प्रक्षिपति । अत्र अग्न्यादीनां पूर्वपूर्वस्याभावे उत्तरोत्तरस्मिन् समिदाधानं कर्तव्यम् सर्वथा लोपो न कर्तव्यः तत्र सूर्यादिषु संस्मृत्य तद्रश्मियुक्तप्रदेशे समिदाधानम् । अपां संनिधानात् तदपेक्षया तासाम् इति स्त्रीलिङ्गेन प्रतिनिर्देशः । तासां तेषाम् अग्न्यादीनाम् अर्चींषि दीप्तयः अभ्रे अन्तरिक्षे पृथक् चरन्ति असंकीर्णं वर्तन्ते । यद्वा अभ्रे उदकपूर्णे मेघे धनुराकारेण पृथक् पृथग् वर्तन्ते । तासाम् । पूर्ववत् स्त्रीलिङ्गनिर्देशः । तेषाम् अग्न्यादीनां ब्रह्मचारिणा समिध्यमानानाम् आज्यादिकं कार्यम् । अग्न्यादयो ब्रह्मचारिसमिन्धनेन आज्यादिकम् उत्पादयन्तीत्यर्थः । आज्यम् इत्यनेन गोसमृद्धिरुक्ता । पुरुष इत्यनेन पुत्रादिसमृद्धिः । वर्षम् इति काले वृष्टिप्रादुर्भावः । आप इति वापीकूपतटाकादिसमृद्धिः ॥

चतुर्थी ॥

आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥ १४ ॥

आऽचार्यः । मृत्युः । वरुणः । सोमः । ओषधयः । पयः ।
जीमूताः । आसन् । सत्वानः । तैः । इदम् । स्वः । आऽभृतम् ॥१४॥

आचार्य एव मृत्युः मारयिता देवः । अपराधाचरणाद् रुष्टस्तस्य जीवनम् अपहरतीत्यर्थः । तथा स एव आचार्यो वरुणः दुरितस्य वार-

१ P चरन्ति. We with P J Cp. २ A B B[h] C D E R Cs ३ for १. We with K K[m] S[m] V.

यिता देवः । परिचर्या[1]परं ब्रह्मचारिणं पापान्निवारयतीत्यर्थः । तथा आचार्य एव सोमश्चन्द्रमाः तद्वद् आह्लादकरत्वात् । ओषधयः व्रीहियवाद्याः । पयः क्षीरम् । तत् सर्वम् आचार्यात्मकमेव तत्प्रसादलभ्यत्वात् । यद्वा यो मृत्युर्यमः स नचिकेतसे ब्रह्मविद्याम् उपदिश्य आचार्यः संपन्नः । वरुणोपि भृगवे ताम् उपदिश्य आचार्योभवत् । एवं सोमोपीति । सर्वदेवतात्मक आचार्य इत्यर्थः । तत्र आचार्यरूपस्य वरुणस्य ये सत्वानः सदनशीला अनुचरास्ते जीमूता आसन् जीवनम् उदकं तस्य मूतवद् भर्तारः जलपूर्णा मेघा अभवन् । तैर्जीमूतैः इदं स्वः सुष्ठु अरणशीलम् उदकम् आभृतम् आहृतम् । वृष्ट्यर्थम् आत्मनि धारितम् इत्यर्थः । यद्वा इदं स्वः सुप्रापं सर्वं जगत् आभृतम् । वृष्ट्या समन्तात् पोषितम् इत्यर्थः ॥

पञ्चमी ॥

अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो॑ भू॒त्वा वरु॑णो॒[१] यद्य॒दैच्छ॑त् प्र॒जाप॑तौ[१] ।
तद् ब्र॑ह्मचा॒री प्राय॑च्छ॒त्[२] स्वान् मि॒त्रो अध्या॒त्मन॑ः ॥ १५ ॥

अ॒मा । घृ॒तम् । कृ॒णु॒ते॒ । केव॑लम् । आ॒ऽचा॒र्य॑ः । भू॒त्वा । वरु॑णः । यत्ऽय॑त् । ऐच्छ॑त् । प्र॒जाऽप॑तौ ।
तत् । ब्र॒ह्म॒ऽचा॒री । प्र । अ॒य॒च्छ॒त् । स्वान् । मि॒त्रः । अधि॑ । आ॒त्मन॑ः ॥१५॥

वरुणो देवः आचार्यो भूत्वा घृतम् क्षरणशीलम् उदकं केवलम् अमा सह कृणुते कुरुते । उदकमेव अनन्यसाधारणं स्वम् आत्मना सहितं करोतीत्यर्थः । स वरुणः प्रजापतौ स्वजनके ब्रह्मणि यद्यत् फलम् ऐच्छत् मित्रो देवो ब्रह्मचारी भूत्वा स्वकीयब्रह्मचर्यमाहात्म्येन स्वात्[*] स्वकीयात् आत्मनः शरीरात् । ⌛ अधिः पञ्चम्यर्थानुवादी । ल्यब्लोपे च इयं पञ्चमी ⌛ । स्वशरीरम् अनपेक्ष्येत्यर्थः । तत् अपेक्षितं सर्वम् आचार्य-

१ So we read and divide with **A B $\overset{h}{\mathbf{B}}$ C D E K $\overset{m}{\mathbf{K}}$ R $\overset{m}{\mathbf{S}}$ P $\overset{2}{\mathbf{P}}$ J V C**s, Sâyaṇa's text the *Panchapaṭalikâ* and the *Bṛihatsarvânukramaṇikâ*. See **R**w. २ **B $\overset{h}{\mathbf{B}}$** प्राय॑छ॒न्त्स्वा°. We with **A C D E K $\overset{m}{\mathbf{K}}$ R $\overset{m}{\mathbf{S}}$ V C**s.

1 **S′** °परब्रह्म° for °परं ब्रह्म°.

भूताय वरुणाय प्रायच्छत् दत्तवान् । ततश्च शिष्येण सता ब्रह्मचारिणा विद्योपदेष्टुर्गुरोः प्रीतिकरम् अपेक्षितं धनं संपाद्य प्रदातव्यम् इत्ययमपि एको नियमो ब्रह्मचारिण उक्तो वेदितव्यः ॥

षष्ठी ॥

आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
प्रजापतिर्वि राजति विराडिन्द्रोऽभवद् वशी ॥ १६ ॥

आऽचार्यः । ब्रह्मऽचारी । ब्रह्मऽचारी । प्रजाऽपतिः ।
प्रजाऽपतिः । वि । राजति । विऽराट् । इन्द्रः । अभवत् । वशी ॥ १६ ॥

आचार्यः प्रथमं विद्याम् उपदिश्य ब्रह्मचार्यात्मना जातः । स च ब्रह्मचारी तपसा ब्रह्मचर्येण अधिकं महिमानं प्राप्य प्रजापतिः जगत्स्रष्टा अभवत् । स च प्रजापतिः वि राजति विराड् भवति । "यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" [श्वे° ६. १८] इति श्रुत्युक्तः स्थूलप्रपञ्चशरीराभिमानी ईश्वरो विराट् । स च वशी स्वतन्त्रः इन्द्रः परमैश्वर्ययुक्तः सर्वजगत्स्रष्टा परमात्मा अभवत् । ततः आचार्यः परंपरया सर्वदेवतात्मक इति तस्य माहात्म्यं केन वर्णयितुं शक्यम् इति भावः ॥

सप्तमी ॥

ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ १७ ॥

ब्रह्मऽचर्येण । तपसा । राजा । राष्ट्रम् । वि । रक्षति ।
आऽचार्यः । ब्रह्मऽचर्येण । ब्रह्मऽचारिणम् । इच्छते ॥ १७ ॥

ब्रह्म वेदः तदध्ययनार्थम् आचर्यम्[1] आचरणीयं समिदाधानभैक्षचर्योर्ध्वरेतस्कत्वादिकं ब्रह्मचारिभिरनुष्ठीयमानं कर्म ब्रह्मचर्यम् । तेन ब्रह्मचर्येण तपसा तत्कृतेन उपवासादिव्रतनियमेन च राजा राष्ट्रं स्वकीयं वि

1 S′ आचार्यं for आचर्यम्.

रक्षति विशेषेण पालयति । यस्य राज्ञो जनपदे ब्रह्मचर्येण युक्ताः पुरुषास्तपश्चरन्ति तदीयं राष्ट्रम् अभिवर्धत इत्यर्थः । यद्वा राज्ञः कर्तव्यत्वेन कालविशेषेषु श्रुतिस्मृत्युदितं ब्रह्मचर्यं तपोऽनुतिष्ठन् राजा तेनैव ब्रह्मचर्येण तपसा राष्ट्रं पालयतीत्यर्थः । आचार्योपि ब्रह्मचर्येण नियमेन ब्रह्मचारिणम् शिष्यम् इच्छते आत्मनोभिलष्यति । ब्रह्मचर्यनियमस्थमेव आचार्यं शिष्या उपगच्छन्तीत्यर्थः । ⌛ इषु इच्छायाम् । व्यत्ययेन आत्मनेपदम् । "इषुगमियमां छः" इति छत्वम् ⌛ ॥

अष्टमी ॥

ब्रह्मचर्येण कन्या३ युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीर्षति ॥ १८ ॥

ब्रह्मऽचर्येण । कन्या । युवानम् । विन्दते । पतिम् ।
अनड्वान् । ब्रह्मऽचर्येण । अश्वः । घासम् । जिगीर्षति ॥ १८ ॥

अत्रापि ब्रह्मचर्यं प्रशस्यते । कन्या अकृतविवाहा स्त्री ब्रह्मचर्यं चरन्ती तेन ब्रह्मचर्येण युवानम् युवत्वगुणोपेतम् उत्कृष्टं पतिं विन्दते लभते ॥ किं बहुना पशुजातिरपि ब्रह्मचर्येण स्वाभिलषितं फलं लभत इत्याह अनड्वान् इति । अनड्वान् अनो वहन् पुंगवः ब्रह्मचर्येण ऊर्ध्वरेतस्कत्वादिना धर्मेण अनोवहनादिकं स्वकार्यं निर्वर्तयन् उत्कृष्टं पतिं लभते । तथा अश्वः ब्रह्मचर्येण घासम् भक्षणीयं तृणादिकं जिगीर्षति भक्षितुम् इच्छति ॥

नवमी ॥

ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्व१राभरत् ॥ १९ ॥

ब्रह्मऽचर्येण । तपसा । देवाः । मृत्युम् । अप । अघ्नत ।
इन्द्रः । ह । ब्रह्मऽचर्येण । देवेभ्यः । स्वः । आ । अभरत् ॥ १९ ॥

---

१ B जिगीषति. V A B[h] C D E K[m] Cp जिगीषति. We with K R S[m] Cs. २ P P[2] जिगीषति. J Cp. जिगीषति. We with J partly, and Sâyaṇa as to the repha. ३ B B[h] C D E S[m] ३ for १. We with K K[m] V Cs.

ब्रह्मचर्यरूपेण तपसा देवाः अग्न्यादयो मृत्युम् मरणम् अपाघ्नत अपहतवन्तः । अमर्त्याः संपन्ना इत्यर्थः । इन्द्रो ह इन्द्रोपि ब्रह्मचर्येणैव साधनेन देवेभ्यः देवानाम् अर्थे स्वः स्वर्गम् आभरत् आहरत् ॥

दशमी ॥

ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिणः ॥ २० ॥ (१५)

ओषधयः । भूतऽभव्यम् । अहोरात्रे इति । वनस्पतिः ।
सम्ऽवत्सरः । सह । ऋतुऽभिः । ते । जाताः । ब्रह्मऽचारिणः ॥ २० ॥ (१५)

ओषः पाकः आसु धीयत इति ओषधयो व्रीहियवाद्याः अरण्यजा वीरुधश्च । भूतभव्यम् भूतम् उत्पन्नं चराचरात्मकं भव्यम् उत्पत्स्यमानम् । अहोरात्रे अहश्च रात्रिश्च । ⧗ "हेमन्तशिशिरावहोरात्रे च च्छन्दसि" इति नपुंसकलिङ्गता निपात्यते ⧗ । वनस्पतिः वनानां पालयिता देवः । ⧗ "पारस्करप्रभृतीनि च संज्ञायाम्" इति सुट् । "उभे वनस्पत्यादिषु युगपत्" इति उभयपदप्रकृतिस्वरत्वम् ⧗ । संवसन्ति अस्मिन्निति संवत्सरो द्वादशमासात्मकः कालः ऋतुभिः वसन्ताद्यैः षड्भिः सह । ते ओषध्यादयः अनुक्रान्ताः सर्वे ब्रह्मचारिणस्तपोमाहात्म्यात् जाताः उत्पन्नाः ॥

[इति] तृतीयेनुवाके द्वितीयं सूक्तम् ॥

तृतीयसूक्ते प्रथमा ॥

पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥ २१ ॥

पार्थिवाः । दिव्याः । पशवः । आरण्याः । ग्राम्याः । च । ये ।
अपक्षाः । पक्षिणः । च । ये । ते । जाताः । ब्रह्मऽचारिणः ॥ २१ ॥

---

१ So we with A B B^h C D E K K^m R S^m V. See Rw. २ B आपक्षाः. K^m अपक्षाः.
३ So P P^2 J Cp.

पार्थिवाः पृथिव्याः संबन्धिनो जनाः । ⧗ "पृथिव्या ञाञौ" इति "तस्येदम्"-अर्थे अञ् प्रत्ययः ⧗ । तथा दिव्याः दिवि भवाः । ⧗ "द्युप्रागपागुदक्प्रतीचो यत्" इति शैषिको यत् प्रत्ययः ⧗ । आरण्याः अरण्ये भवाः पशवः सिंहशार्दूलहरिणाद्याः । ग्राम्याः गवाश्वमहिषाद्याः । एवंभूता ये पशवः सन्ति तथा अपक्षाः पक्षरहिताः प्राणिनो ये सन्ति पक्षिणः पक्षवन्तश्च ये सन्ति ते सर्वे ब्रह्मचारिणो जाताः ब्रह्मचर्यप्रभावाद् उत्पन्ना इत्यर्थः ॥

द्वितीया ॥

पृथक् सर्वे प्राजापत्याः प्राणानात्मसु बिभ्रति ।
तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥ २२ ॥

पृथक् । सर्वे । प्राजाऽपत्याः । प्राणान् । आत्मऽसु । बिभ्रति[1] ।
तान् । सर्वान् । ब्रह्म । रक्षति । ब्रह्मऽचारिणि । आऽभृतम् ॥ २२ ॥

प्राजापत्याः प्रजापतिना सृष्टा देवमनुष्याद्याः सर्वे आत्मसु शरीरेषु प्राणान् पृथक् नाना स्वस्वसंबन्धिन एव बिभ्रति धारयन्ति पोषयन्ति वा । ⧗ डुभृञ् धारणपोषणयोः । जुहोत्यादित्वात् शपः श्लुः । "अदभ्यस्तात्" इति झस्य अदादेशः । "भृञामित्" इति अभ्यासस्य इत्त्वम् ⧗ । तान् सर्वान् प्राणान् ब्रह्मचारिणि आचार्यमुखाद् आभृतम् आहृतम् अध्ययनेन संपादितं ब्रह्म वेदात्मकं रक्षति पालयति । ब्रह्मचार्यधीतं ब्रह्म सर्वप्राणिरक्षणक्षमम् इत्यर्थः ॥

तृतीया ॥

देवानामेतत् परिषूतमनभ्यारूढं चरति रोचमानम् ।
तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥ २३ ॥

देवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् ।
तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवाः । च । सर्वे । अमृतेन । साकम् ॥ २३ ॥

---

१ P विभ्रंति. We with P[2] J Cp.

एतत् सर्वापरोक्षं परब्रह्म देवानां परिषूतम् परिगृहीतम् । आत्मतया साक्षात्कृतम् इत्यर्थः । [रोचमानम्] स्वप्रकाशचिद्रूपतया दीप्यमानम् अनभ्यारूढम् अन्यैरनाक्रान्तं सर्वोत्कर्षेण चरति वर्तते । तस्मात् सकाशाद् ब्राह्मणम् ब्रह्मणः संबन्धि ब्राह्मणस्य वा असाधारणं स्वं ज्येष्ठम् प्रवृद्धतमं प्रशस्यतमं वा ब्रह्म वेदात्मकं जातम् प्रादुर्भूतम् । "अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेदः" इति श्रुतेः [बृ० आ० २. ४. १०] । देवाः तत्प्रतिपाद्या अग्न्यादयश्च सर्वे अमृतेन स्वोपभोग्येन अमृतत्वप्रापकेन सुधारसेन साकम् सह जाता इत्यर्थः ॥

चतुर्थी ॥

ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
प्राणापानौ जनयन्नाद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥ २४ ॥

ब्रह्मऽचारी । ब्रह्म । भ्राजत् । बिभर्ति । तस्मिन् । देवाः । अधि । विश्वे ।
समऽओताः ।
प्राणापानौ । जनयन् । आत् । विऽआनम् । वाचम् । मनः । हृदयम् । ब्रह्म ।
मेधाम् ॥ २४ ॥

ब्रह्मचारी ब्रह्मचर्यवान् पुरुषो भ्राजत् दीप्यमानं ब्रह्म वेदात्मकं बिभर्ति धारयति । तस्मिन् अधि उपरि विश्वे सर्वे देवाः समोताः संबद्धाः । "यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति" इति श्रुतेः [तै० आ० २. १५] । स च सर्वेषां देवानां निवासभूतो ब्रह्मचारी प्राणापानौ सर्वप्राणिसंबन्धिनौ जनयन् उत्पादयन् वर्तते । आत् अनन्तरं व्यानम् । "अथ यः प्राणापानयोः संधिः स व्यानः" इति [छा० १. ३. ३] श्रुत्यन्तरप्रसिद्धं व्यानाख्यं वायुम् वाचम् वागिन्द्रियं परापश्यन्त्यादिरूपां वा शब्दात्मिकां वाचम् मनः सर्वेन्द्रियानुग्राहकम् अन्तःकरणम् हृदयम् तदावासस्थानभूतं हृदयकमलम् ब्रह्म वेदात्मकम् मेधाम् आशुविद्याग्रहणकुशलां बुद्धिम् एतत् सर्वं ब्रह्मचारी जनयन् वर्तते ॥

चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥ २५ ॥

चक्षुः । श्रोत्रम् । यशः । अस्मासु । धेहि । अन्नम् । रेतः । लोहितम् । उदरम् ॥ २५ ॥

तानि[1] कल्पद्[1] ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत् तप्यमानः समुद्रे ।
स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते[2] ॥ २६ ॥ (१६)

तानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तपः । अतिष्ठत् । तप्यमानः[3] । समुद्रे ।

सः । स्नातः । बभ्रुः । पिङ्गलः । पृथिव्याम् । बहु । रोचते ॥ २६ ॥ (१६)

पञ्चमी ॥ हे ब्रह्मन् ब्रह्मचार्यात्मक अस्मासु स्तोतृषु चक्षुः रूपग्राहकम् इन्द्रियं श्रोत्रम् शब्दग्राहकम् । प्राधान्याद् उपलक्षणत्वेन एतद् इन्द्रियद्वयम् उक्तम् । चक्षुःश्रोत्रादीनि सर्वाणि इन्द्रियाणि यशः कीर्तिं च अस्मासु धेहि धारय । आन्ध्यबाधिर्यादिकं कदाचिदपि अस्माकं मा भूद् इत्यर्थः । तथा भोज्यम् अन्नम् पुत्रादिकारणं रेतः लोहितम् शरीरगतम् असृक् उदरम् उदरोपलक्षितं समस्तशरीरम् । तानि एतानि अन्नादीनि ब्रह्मचारी कल्पत् कल्पयन् सलिलस्य पृष्ठे उदकस्य मध्ये तपस्तप्यमानः [समुद्रे] अतिष्ठत् । वर्तत इत्यर्थः । स तपस्वी ब्रह्मचारी अनिशं स्नातः स्नानेन पवित्रीकृतः बभ्रुः बभ्रुवर्णः । एतदेव विव्रियते पिङ्गल इति । पिङ्गलवर्णः सन् पृथिव्याम् भूम्यां बहु अधिकं रोचते दीप्यते ॥

[इति] तृतीयेनुवाके तृतीयं सूक्तम् ॥

"अग्निं ब्रूमः" इत्यादि सूक्तद्वयम् अर्थसूक्तम् । तस्य बृहद्गणे लघुगणे च पाठात् शान्त्युदकाभिमन्त्रणादौ विनियोगः ॥

अस्यार्थसूक्तस्य "मुञ्चन्तु मा [११. ८. ७] भवाशर्वाविदम् [११. ८. ९] या देवीः पञ्च [११. ८. २२] यन्मातली रथक्रीतम्" [११. ८. २३] इत्येताश्चतस्र ऋचो वर्जयित्वा सप्तप्रतीके अंहोलिङ्गगणे पाठात् "अनुक्ता-

---

१ So A B B̊ C D E K K̊ R S̊ V Cs, and Sâyaṇa's text in S′. २ B रोचत. ३ P तपमानः.

न्यप्रतिषिद्धानि भैषज्यानाम् अंहोलिङ्गाभिः" [कौ. ४. ८] इत्यादिषु सर्वभैषज्यादिकर्मसु गणप्रयुक्तो विनियोगोनुसंधेयः ॥

तथा "हस्तिरथदानानुक्रमं वक्ष्ये" इति प्रक्रम्य उक्तं परिशिष्टे ।

तस्मात् सर्वेषु दानेष्वनुक्तविधिकेषु[1] च ।

अग्निं ब्रूम इति सूक्तेनाज्यतन्त्रेण होमयेत् । इति [प॰ १४. १] ॥

तत्र प्रथमा ॥

अ॒ग्निं ब्रू॑मो॒ वन॒स्पती॑नोष॑धीरु॒त वी॒रुधः॑ ।
इन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ १ ॥

अ॒ग्निम् । ब्रू॒मः॒ । वन॒स्पती॑न् । ओष॑धीः । उ॒त । वी॒रुधः॑ ।
इन्द्र॑म् । बृह॒स्पति॑म् । सूर्य॑म् । ते । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥ १ ॥

अग्निः अग्रणीः सर्वेषां देवानाम् आदिभूतो देवः । "अग्निरग्रे प्रथमो देवतानाम्" इति [तै॰ ब्रा॰ २. ४. ३. ३] श्रुतेः । तादृशम् अग्निं ब्रूमः स्तुमः । यद्वा इष्टफलं याचामहे । तथा वनस्पतीन् पृथिव्यधिदैवतेन तेनाग्निना संवर्धितान् महावृक्षान् ओषधीः व्रीहियवाद्याः [उत अपि च] वीरुधः आरण्या लतारूपाः ताः सर्वा ब्रूमः स्तुमः । तथा इन्द्रम् द्युलोकाधिपतिं बृहस्पतिम् बृहतां देवानां पतिं सूर्यम् सर्वस्य प्रेरकम् आदित्यं च ब्रूमः स्तुमः । ते सर्वे नः अस्मान् अंहसः पापात् मुञ्चन्तु ॥

द्वितीया ॥

ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॑मथो॒ भग॑म् ।
अंशं॒ विव॑स्वन्तं ब्रूमस्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ २ ॥

ब्रू॒मः । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् ।
अंश॑म् । विव॑स्वन्तम् । ब्रू॒मः॒ । ते । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥ २ ॥

अत्र वरुणादयः सूर्यमूर्तयः स्तूयन्ते । राजानम् राजमानम् ईशितारं

1 S′ विध्युक्त॰ for अनुक्त॰ which we with the *Paris′ishṭa*.

वा वरुणं देवं ब्रूमः स्तुमः । मित्रम् सर्वस्य मित्रभूतं देवं विष्णुम् व्यापनशीलं देवम् अथो अपि च भगम् भजनीयं देवम् अंशम् एतत्संज्ञं देवं विवस्वन्तम् विवस्वत्संज्ञं देवं ब्रूमः स्तुमः । ते नो मुञ्चन्त्वंहस इति समानम् ॥ एते च आदित्यास्तैत्तिरीयेऽनुक्रम्यन्ते । "मित्रश्च वरुणश्च । धाता चार्यमा च । अंशश्च भगश्च । इन्द्रश्च विवस्वांश्चेत्येते" [तै॰ आ॰ १. १३. ३] । आचार्यैस्तु द्वादशादित्याः परिगणिताः ।

धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्द्रयुताः ।
पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः । इति ॥

तृतीया ॥

ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ३ ॥

ब्रूमः । देवम् । सवितारम् । धातारम् । उत । पूषणम् ।
त्वष्टारम् । अग्रियम् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ३ ॥

देवम्[1] दानादिगुणयुक्तं सवितारम् सर्वस्य प्रेरकं[2] ब्रूमः स्तुमः । तथा धातारम् । उतशब्दः अप्यर्थे । पूषणमपि स्तुमः । अग्रियम् अग्रे भवः अग्रियः । प्रथमगण्य इत्यर्थः । ⌛"अग्राद् यत्" "घच्छौ च" इति घच् प्रत्ययः । चित्त्वाद् अन्तोदात्तत्वम्⌛ । तादृशं त्वष्टारं ब्रूमः स्तुमः ॥ गतम् अन्यत् ॥

चतुर्थी ॥

गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥ ४ ॥

गन्धर्वऽअप्सरसः । ब्रूमः । अश्विना । ब्रह्मणः । पतिम् ।
अर्यमा । नाम । यः । देवः । ते । नः । मुञ्चन्तु । अंहसः ॥ ४ ॥

गन्धर्वाश्च अप्सरसश्च गन्धर्वाप्सरसः । "अग्निर्गन्धर्वस्तस्यौषधयोप्सर-

1 S′ एवं. 2 S′ inserts देवं after प्रेरकं.

सः" [तै॰ सं॰ ३. ४. ७. १] इत्यादिमन्त्रवर्णप्रसिद्धान् गन्धर्वाप्सरोरूपान् देवगणान् ब्रूमः स्तुमः । तथा अश्विना अश्विनौ स्तुमः । ब्रह्मणो वेदराशेः पतिं स्वामिनम् तथा अर्यमा नाम अर्यमेति प्रसिद्धो यो देवोस्ति तमपि स्तुमः । ते सर्वे नः अस्मान् अंहसः मुञ्चन्त्विति शेषं समानम् ॥

पञ्चमी ॥

अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।
विश्वानादित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ५ ॥

अहोरात्रे इति । इदम् । ब्रूमः । सूर्याचन्द्रमसौ । उभा ।
विश्वान् । आदित्यान् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ५ ॥

अहश्च रात्रिश्च अहोरात्रे ते उद्दिश्य इदं स्तुतिवाक्यं ब्रूमः । सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोरधिष्ठातृदेवौ उभा उभौ स्तुमः । विश्वान् [सर्वान्] आदित्यान् अदितेः पुत्रान् ब्रूमः स्तुमः ॥ गतम् अन्यत् ॥

षष्ठी ॥

वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।
आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ६ ॥

वातम् । ब्रूमः । पर्जन्यम् । अन्तरिक्षम् । अथो इति । दिशः ।
आशाः । च । सर्वाः । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ६ ॥

वातम् वायुं ब्रूमः स्तुमः । पर्जन्यम् वृष्टिप्रदं देवम् अन्तरिक्षम् आकाशम् अथो अपि च दिशः दिग्देवता आशाः विदिशश्च सर्वास्ता ब्रूमः स्तुमः ॥

सप्तमी ॥

मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।
सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥ ७ ॥

मुञ्चन्तु । मा । शपथ्यात् । अहोरात्रे इति । अथो इति । उषाः ।
सोमः । मा । देवः । मुञ्चतु । यम् । आहुः । चन्द्रमाः । इति ॥ ७ ॥

शपथ्यात् शपथप्रभवात् पापात् मा मां मुञ्चन्तु अहोरात्रे अहरभिमानिदेवता रात्र्यभिमानिदेवता च अथो अपि च उषाः अहोरात्रयोः संधौ वर्तमाना उषःकालाभिमानिनी देवता । तासां बहुत्वात् मुञ्चन्तु इति बहुवचनम् । तथा सोमो देवः मा मां तस्मात् पापात् मुञ्चतु । तं विशिनष्टि । यं सोमं चन्द्रमा इति आहुः अभिज्ञाः कथयन्ति । स सोमोत्र मोचक इत्यर्थः ॥

अष्टमी ॥

पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ८ ॥

पार्थिवाः । दिव्याः । पशवः । आरण्याः । उत । ये । मृगाः ।
शकुन्तान् । पक्षिणः । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ८ ॥

पार्थिवाः इत्यादि[1] व्याख्यातम् [११. ७. २१] । हरिणशार्दूलसिंहाद्या मृगाः । तान् पार्थिवादीन् स्तुम इति शेषः । शकुन्तान् शकुनभूतान् पक्षिणः पिङ्गलादीन् ब्रूमः स्तुमः ॥

नवमी ॥

भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।
इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥ ९ ॥

भवाशर्वौ । इदम् । ब्रूमः । रुद्रम् । पशुऽपतिः । च । यः ।
इषूः । याः । एषाम् । सम्ऽविद्म । ताः । नः । सन्तु । सदा । शिवाः ॥ ९ ॥

भवश्च शर्वश्च भवाशर्वौ । तावुद्दिश्य इदं स्तुतिवाक्यं ब्रूमः वदामः । तथा रुद्रं स्तुमः । यश्च पशुपतिर्देवस्तमपि स्तुमः । एते च देवाः "भवाशर्वौ मृडतम" [११. २] इत्यस्मिन् सूक्ते प्रपञ्चिताः । एषां देवानां

1 S' omit इत्या°.

या इषूः शरान् संविद्मः संजानीमः ता नः अस्माकं सदा सर्वदा शिवाः सुखहेतवः [सन्तु] भवन्तु ॥

दशमी ॥

दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥ १० ॥ (१७)

दिवम् । ब्रूमः । नक्षत्राणि । भूमिम् । यक्षाणि । पर्वतान् ।
समुद्राः । नद्यः । वेशन्ताः । ते । नः । मुञ्चन्तु । अंहसः ॥ १० ॥ (१७)

दिवम् द्योतमानां द्यां ब्रूमः स्तुमः । तत्राश्रितानि नक्षत्राणि पुण्यकृतां धामानि । "सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि" इति श्रुतेः [तै॰ सं॰ ५. ४. १. ३] । तानि स्तुमः । तथा भूमिं स्तुमः । यक्षाणि पूज्यानि तत्रत्यानि पुण्यक्षेत्राणि स्तुमः । तथा पर्वतान् हिमवत्प्रमुखान् महागिरीन् स्तुमः । समुद्राः सप्तसंख्याका भूम्याश्रिताः प्रसिद्धाः । नद्यश्च गङ्गाद्याः । वेशन्ताः तदपेक्षया अल्पानि अन्यानि सरांसि । तान् सर्वान् स्तुमः ॥

[इति] तृतीयेनुवाके चतुर्थं सूक्तम् ॥

"सप्तर्षीन् वा इदं ब्रूमः" इति सूक्तस्य पूर्ववद् विनियोगः ।

श्रौतदर्शपूर्णमासयोः प्राशित्रभक्षणानन्तरम् "यन्मातली रथक्रीतम्" इत्यनया ब्रह्मा अद्भिर्मार्जयेत् । तद् उक्तं वैताने । "प्राशित्रं यवमात्रम् अधस्ताद् उपरिष्टाद् वाभिघारितम्" इत्युपक्रम्य "मातल्याद्भिर्मार्जयित्वा प्राणान् संस्पृशते" इति [वै॰ १. ३] ॥

पञ्चमसूक्ते प्रथमा ॥

सप्तर्षीन् वा इदं ब्रूमोपो देवीः प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११ ॥

---

१ P J यक्षाणि । We with P̊ Cp. २ B K K D S V सप्तऋषी॰. Dc सप्तषीन् corrected to सप्तऋषीन्. Cs सप्तर्षी॰. Sâyaṇa's text : सप्तऋषी॰. We with A B C E R.

---

1 S′ भवंति. The text in S′ is संतु. 2 S′ एषां तानि for एतानि.

सप्तऽऋषीन् । वै । इदम् । ब्रूमः । अपः । देवीः । प्रजाऽपतिम् ।
पितॄन् । यमऽश्रेष्ठान् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ ११ ॥

सप्तर्षीन् उद्दिश्य खलु इदं स्तुतिवचनं ब्रूमः । अथ वा तान् इदं फलं याचामहे । तथा अपो देवीः अब्देवताः प्रथमसृष्टाः स्तुमः । प्रजापतिम् तासां स्रष्टारं स्तुमः । तथा यमश्रेष्ठान् यमः श्रेष्ठो मुख्योधिपतिर्येषां तान् पितॄन् बर्हिषदग्निष्वात्तादीन् ब्रूमः स्तुमः ॥

द्वितीया ॥

ये देवा दिविषदो अन्तरिक्षसदश्च ये ।
पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥ १२ ॥
ये । देवाः । दिविऽसदः । अन्तरिक्षऽसदः । च । ये ।
पृथिव्याम् । शक्राः । ये । श्रिताः । ते । नः । मुञ्चन्तु । अंहसः ॥ १२ ॥

ये दिविसदः द्युलोके सीदन्तः उपविशन्तो देवाः । षद्लृ विशरणगत्यवसादनेषु । "सत्सूद्विष॰" इत्यादिना क्विप् । तथा ये च अन्तरिक्षसदः अन्तरिक्षे उपविष्टाः तथा पृथिव्याम् भूमौ शक्राः शक्ता देवा ये श्रिताः आश्रिताः ॥ अन्यद् गतम् ॥

तृतीया ॥

आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।
अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥ १३ ॥
आदित्याः । रुद्राः । वसवः । दिवि । देवाः । अथर्वाणः ।
अङ्गिरसः । मनीषिणः । ते । नः । मुञ्चन्तु । अंहसः ॥ १३ ॥

आदित्याः अदितेः पुत्रा द्वादशसंख्याकाः । रुद्राः एकादश । वसवः अष्टौ । एते च दिवि वर्तमाना गणत्रयात्मका देवाः । विंशतिकाण्डात्मकस्यास्य वेदस्य द्रष्टारो महर्षयः अथर्वाणस्तेपि तत्संख्याकाः । अङ्गि-

---

१ P P̊ J सप्त॰ऽर्षीन् । We with Cp. २ P शक्रः । We with P̊ J Cp.

---

1 So S'. S''s text too : दिविसदः.

रसोपि अस्य वेदस्य द्रष्टारस्तावन्तः । मनीषिणः मनस ईषिणः सर्वज्ञाः ते सर्वे अस्माभिः स्तुताः नः अस्मान् अंहसः पापात् मुञ्चन्तु ॥[1]

चतुर्थी ॥

यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ १४ ॥

यज्ञम् । ब्रूमः । यजमानम् । ऋचः । सामानि । भेषजा ।
यजूंषि । होत्राः । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ १४ ॥

यज्ञम् अग्निष्टोमादिकं ब्रूमः स्तुमः । तथा यजमानम् तत्फलभाजं स्तुमः । ऋचः तस्मिन् यज्ञे याज्यादिरूपेण[2] विनियुक्ताः पादबद्धा मन्त्राः । तथा सामानि फलवद्यज्ञसाधनस्तोत्रनिर्वर्तकानि प्रगीतमन्त्रात्मकानि रथन्तरबृहद्वैरूपादीनि । भेषजा यानि च भेषजानि शान्तिकराणि वामदेव्यादीनि । यजूंषि तस्मिन् यज्ञे आध्वर्यवकर्मसु करणतया विनियुक्तानि क्रियमाणानुवादीनि वा प्रश्लिष्टपठितानि । होत्राः । होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टा अच्छावाक आग्नीध्र इति तस्मिन् सोमयागे सप्त वषट्कर्तारः तेषां क्रिया होत्राः । एतान् ऋक्सामादीन् यज्ञावयवान् ब्रूमः स्तुमः ॥

पञ्चमी ॥

पञ्च[1] राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥ १५ ॥

पञ्च । राज्यानि । वीरुधाम् । सोमऽश्रेष्ठानि । ब्रूमः ।
दर्भः । भङ्गः । यवः । सहः । ते । नः । मुञ्चन्तु । अंहसः ॥ १५ ॥

वीरुधाम् विरोहणशीलानाम् ओषधीनां पञ्चसंख्याकानि राज्यानि रा-

---

१ K $\overset{m}{K}$ V पञ्च राज्यानि. Dc पंचं राज्यानि changed to पंच राज्यानि. We with A B $\overset{h}{B}$ C D E R $\overset{m}{S}$ Cs.

---

1 S′ omit पापात् मु°. 2 S′ omits या° and leaves space for five letters before °ज्या°.

ज्ञा भिषजा विनियुज्यमानानि पत्त्रकाण्डपुष्पफलमूलात्मकानि सोमश्रेष्ठानि । सोमो ह्यासां राजा । अतः स एव श्रेष्ठः प्रशस्यतमो येषां तथाविधानि वीरुधां राज्यानि ब्रूमः स्तुमः । तथा दर्भः कुशमयः प्रसिद्धः । भङ्गः शणः । यवः ओषधिविशेषः प्रसिद्धः । सहः कश्चिद् ओषधिविशेषः । एतेपि अस्माभिः स्तुताः पापाद् मुञ्चन्तु ॥ यद्वा वीरुधाम् ओषधीनां मध्ये पञ्चसंख्याकानि [1]राज्यानि राज्ञः सोमस्य कर्माणि क्रियाविशेषनिष्पन्नानि । भेषजानीत्यर्थः । तानि च सोमश्रेष्ठानि सोमो लतारूपेण उत्पन्नः श्रेष्ठः प्रशस्यतमः येषां तानि । एतेन सोमलतात्मकम् एकं राज्यम् इत्युक्तं भवति । दर्भादीनि च [2]चत्वारि एवं पञ्च राज्यानि स्तुम इति ॥

षष्ठी ॥

अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ १६ ॥

अरायान् । ब्रूमः । रक्षांसि । सर्पान् । पुण्यऽजनान् । पितॄन् ।
मृत्यून् । एकऽशतम् । ब्रूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ १६ ॥

[3]अरायान् दानप्रतिबन्धकान् हिंसकान् ब्रूमः स्तुमः । यद्वा अरायाः आर्तिकरा रक्षोवद् बाधकाः पिशाचविशेषाः । तान् ब्रूमः स्तुमः । तथा रक्षांसि । रक्षो रक्षितव्यम् अस्माद् इति यास्कः [नि० ४.१८] । राक्षसान् । सर्पान् पन्नगान् । पुण्यजनान् यातुधानान् । पितॄन् पूर्वपुरुषान् पितृलोकं गतान् । मृत्यून् मारयितॄन् देवान् एकशतम् एकोत्तरशतसंख्याकान् । "शतायुर्वै पुरुषः शतवीर्यः । आत्मैकशतम्[4]" इति [तै० ब्रा० १.७.६.४] श्रुतेर्मर्त्यः पुरुषः एकशतप्रकारः । ततो मारयितुर्मृत्योरपि तावत्प्रकारत्वं युज्यत एव । तथा च अन्यत्रापि मन्त्रवर्णो दृश्यते । "अपास्य [5]योसिनात् पाशान् मृत्यून् एकशतं च" इति । तान् सर्वान् ब्रूमः स्तुमः ॥

---

1 S′ omit राज्यानि रा°. 2 S′ च for चत्वारि. 3 S′ leaves space for two or three letters and then reads यान् for अरायान्. 4 So S′. 5 S′ येसिनात्.

सप्तमी ॥

ऋतून् ब्रूम ऋतुपतीनार्तवानुत हायनान् ।
समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥ १७ ॥

ऋतून् । ब्रूमः । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् ।
समाः । समऽवत्सरान् । मासान् । ते । नः । मुञ्चन्तु । अंहसः ॥१७॥

ऋतून् वसन्ताद्यान् ब्रूमः स्तुमः । तथा ऋतुपतीन् तेषाम् ऋतूनाम् अधिपतीन् । तत्र वसन्तस्य वसवोधिपतयः । "वसन्तेनर्तुना देवा वसवस्त्रिवृता स्तुतम्" इति[1] श्रुतेः [तै° ब्रा° २. ६. १९. १] । ग्रीष्मस्य रुद्रा अधिपतयः । "ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे स्तुतम्" इति [तै° ब्रा° २. ६. १९. १] आम्नानात् । वर्षर्तोरादित्या अधिपतयः । "वर्षाभिर्ऋतुनादित्याः" इति [तै° ब्रा° २. ६. १९. १] श्रूयमाणत्वात् । शरदृतोर्ऋभवोधिपतयः[2] । "शारदेनर्तुना देवा एकविंश ऋभवः स्तुतम्" इति [तै° ब्रा° २. ६. १९. २] श्रुतेः । "हेमन्तशिशिरयोः समासेन" [ऐ° ब्रा° १. १] इति एकत्वश्रवणात् समासेन तयोर्मरुतोधिपतयः । श्रूयते हि । "हेमन्तेनर्तुना देवा मरुतस्त्रिणवे[3] स्तुतम्" इति [तै° ब्रा° २. ६. १९. २] । इत्थं वसुरुद्रादीन् ऋतुपतीन् ब्रूमः स्तुमः । आर्तवान् तत्तदृतुविशेषसंबन्धिनः पदार्थान् । उतशब्दः अप्यर्थे । हायनान् समाः संवत्सरान् इति पर्यायशब्दाश्चान्द्रसौरसावनभेदेन त्रिविधसंवत्सराभिप्रायाः । मासान् चैत्राद्यान् । एतान् सर्वान् ब्रूमः स्तुमः ॥

अष्टमी ॥

एतं देवा दक्षिणतः पश्चात् प्राञ्च उदेत ।
पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥ १८ ॥

आ । इत । देवाः । दक्षिणतः । पश्चात् । प्राञ्चः[१] । उत्ऽएत ।
पुरस्तात् । उत्तरात् । शक्राः । विश्वे । देवाः । समऽएत्य । ते । नः ।
मुञ्चन्तु । अंहसः ॥ १८ ॥

१ P पाञ्चः I. We with P J Cp.

1 S′ इव for इति. 2 S′ शरदृताऋतुताधिपतयः. 3 S′ मरुतस्तृणवे.

हे देवाः दक्षिणतः दक्षिणस्यां दिशि [स्थिता यूयम्] एत आगच्छत । एवं चतसृषु दिक्षु अवस्थिताः सर्वे देवाः समेत्य समागत्य ते यूयम् अस्मान् अंहसः पापात् । मुञ्चतेति शेषः ॥

नवमी ॥

विश्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृ॒ता॒वृधः॑ ।
विश्वा॑भि॒ः पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ १९ ॥

विश्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒ः । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृधः॑ ।
विश्वा॑भिः । पत्नी॑भिः । स॒ह । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥ १९ ॥

विश्वे देवा नाम देवगणाः । तान् उद्दिश्य इदं स्तुतिवचनं ब्रूमः वदामः । यद्वा इदं फलं याचामहे । कीदृशान् । सत्यसंधान् सत्यप्रतिज्ञान् । ऋतावृधः ऋतम् इति सत्यस्य यज्ञस्य वा नामधेयम् तस्य वर्धयितृन् । विश्वाभिः पत्नीभिः विश्वाख्याभिर्देवीभिः सह । तान् ब्रूम इत्यर्थः । ते न इत्यादि समानम् ॥

दशमी ॥

सर्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृ॒ता॒वृधः॑ ।
सर्वा॑भि॒ः पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ २० ॥

सर्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒ः । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृधः॑ ।
सर्वा॑भिः । पत्नी॑भिः । स॒ह । ते । न॒ः । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥ २० ॥

विश्वशब्दस्य स्थाने सर्वशब्द एव विशेषः । उक्तान् अनुक्तांश्च सर्वान् देवान् । अन्यत् पूर्ववद् योज्यम् ॥

एकादशी ॥

भू॒तं ब्रू॑मो भू॒तप॑तिं भू॒ताना॑मु॒त यो व॒शी ।
भू॒तानि॒ सर्वा॑ सं॒गत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥ २१ ॥

भू॒तम् । ब्रू॒म॒ः । भू॒त॒ऽप॑तिम् । भू॒ताना॑म् । उ॒त । यः । व॒शी ।

1 So S′.

भूतानि । सर्वा । सम्ऽगत्यं । ते । नः । मुञ्चन्तु । अंहसः ॥ २१ ॥

भूतम् लब्धसत्ताकं वस्तुमात्रं ब्रूमः स्तुमः । भूतपतिम् तस्य भूतस्य अधिपतिम् ईश्वरम् । उत अपि च तेषां सर्वेषां भूतानां यो वशी वशयिता नियन्ता तमपि स्तुमः । सर्वा सर्वाणि तानि भूतानि संगत्य संभूयागत्य ॥ गतम् अन्यत् ॥

द्वादशी ॥

या देवीः पञ्च प्रदिशो ये देवा द्वादशर्तवः ।

संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥ २२ ॥

याः । देवीः । पञ्च । प्रऽदिशः । ये । देवाः । द्वादश । ऋतवः ।

सम्ऽवत्सरस्य । ये । दंष्ट्राः । ते । नः । सन्तु । सदा । शिवाः ॥ २२ ॥

याः प्रसिद्धाः पञ्चसंख्याकाः प्रदिशः प्रधानदिशः [देवीः] देव्यो दानादिगुणयुक्ता देवतारूपा वा सन्ति ये देवाः दानादिगुणयुक्ता द्वादशसंख्याका ऋतवः "मधुश्च माधवश्च" इत्येवम् [तै° सं° १. ४. १४] अनुक्रान्ता मासाः तथा संवत्सरस्य द्वादशमासात्मकस्य प्रजापतेर्ये दंष्ट्राः दशन्ति खादन्ति एभिरिति दंष्ट्रा दन्तविशेषाः । "दाम्नीशस°" इत्यादिना करणे ष्ट्रन् प्रत्ययः । ते चात्र संवत्सरसंबन्धिनो विष्ट्यादिदुष्टकालात्मकाः । ते सर्वे नः अस्माकं सदा सर्वदा शिवाः कल्याणहेतवः सन्तु ॥

त्रयोदशी ॥

यन्मातली रथक्रीतममृतं वेद भेषजम् ।

तदिन्द्रो अप्सु प्रावेशयत् तदापो दत्त भेषजम् ॥ २३ ॥ (१८)

यत् । मातली । रथऽक्रीतम् । अमृतम् । वेद । भेषजम् ।

तत् । इन्द्रः । अप्ऽसु । प्र । अवेशयत् । तत् । आपः । दत्त । भेषजम् ॥ २३ ॥ (१८)

१ So we read with A B B^h C D E K K^m R S^m V Cs Dc. See Rw.

मातली इन्द्रस्य सारथिः रथक्रीतम् रथस्य क्रयेण लब्धम् अमृतम् अमरणसाधनं यद् भेषजं वेद जानाति तत् भेषजम् इन्द्रस्तस्य रथस्य अधिपतिर्देवः अप्सु उदकेषु प्रावेशयत् प्राक्षिपत् । हे आपः यूयं तत् मातलिना क्रीतम् इन्द्रेण क्षिप्तं भेषजम् औषधं दत्त अस्मभ्यं प्रयच्छत ॥

पञ्चमं सूक्तम् ॥

इति सायणाचार्यविरचिते अथर्वसंहिताभाष्ये एकादशकाण्डे

तृतीयोनुवाकः ॥

चतुर्थेनुवाके षट् सूक्तानि । तत्र आद्यैस्त्रिभिः सूक्तैर्ब्रह्मौदनाख्ये सवयज्ञे हुतशिष्टस्य ओदनस्य सर्वजगत्कारणभूतब्रह्माभेदेन स्तुतिः क्रियते । तत्रैव एषां विनियोगो द्रष्टव्यः ॥

तत्र प्रथमसूक्ते प्रथमा ॥

उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।

उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥ १ ॥

उत्ऽशिष्टे । नाम । रूपम् । च । उत्ऽशिष्टे । लोकः । आऽहितः ।

उत्ऽशिष्टे । इन्द्रः । च । अग्निः । च । विश्वम् । अन्तः । सम्ऽआहितम् ॥ १ ॥

उच्छिष्टे । होमाद् ऊर्ध्वं शिष्यते अवशिष्यत इति हुतावशिष्टः[1] प्राशनार्थ ओदनः उच्छिष्टः । तस्य देवसृष्टिहेतुत्वं तावच्छ्रूयते हि । "अ- "दितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् । तस्या उच्छे- "षणम् अददुः । तत् प्राश्नात् । सा रेतोधत्त । तस्यै धाता चार्यमा "चाजायेताम्" इत्यादि [तै० ब्रा० १.१.९.१] । तथा अस्मिन्नेव[2] वेदे मुण्डकोपनिषदि अन्नस्य सर्वजगद्धेतुता समाम्नास्यते ।

तपसा चीयते ब्रह्म ततोन्नम् अभिजायते ।

अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥

इति [मु० १.१.८] । तस्मिन् उच्छिष्टे हुतशिष्टे अन्ने नाम नामधेयात्मकः शब्दप्रपञ्चः रूपम् तेन निरूपणीयः अर्थप्रपञ्चश्च तद् उभयम् आ-

1 S′ हुतावशिष्टे. 2 S′ तस्मिन्नेव.

हितम् आस्थितम् । नामरूपात्मकः प्रपञ्चस्तस्मिन् कारणभूते समाश्रित्य लब्धसत्ताकोवतिष्ठत इत्यर्थः । यद्वा "अथात आदेशो नेति नेति" [बृ॰ आ॰ २. ३. ११] "नेह नानास्ति किंचन" [बृ॰ आ॰ ४. २. २१] इत्येवं दृश्यप्रपञ्चनिषेधाद् ऊर्ध्वं तदवधित्वेन शिष्यते अवशिष्यत इत्युच्छिष्टं बाधावधित्वेन शिष्यमाणं परं ब्रह्म । तस्मिन् शुक्त्यादौ रजतादिवत् नाम रूपं चेति द्विधाभूतं समस्तं जगत् आहितम् आरोपितम् । वर्तत इत्यर्थः । इत्थं सामान्येन सर्वजगदाधारत्वम् अभिधाय विशेषतो निर्दिशति उच्छिष्टे लोक आहित इत्यादिना । उच्छिष्टे उच्छिष्यमाणे[1] ब्रह्माभिन्ने कारणभूते तस्मिन्नोदने लोकः पृथिव्यादिरूपः सर्वो लोकः आहितः आस्थितः । तस्मिन्नेव उच्छिष्टे द्युलोकाधिपतिः [इन्द्रश्च] पृथिव्यधिपतिः अग्निश्च उभौ आहितौ । किं बहुना एतदुपलक्षितं विश्वम् सर्वं जगत् अन्तः मध्ये समाहितम् सम्यग् ईश्वरेण स्थापितम् ॥

द्वितीया ॥

उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥ २ ॥

उत्ऽशिष्टे । द्यावापृथिवी इति । विश्वम् । भूतम् । सम्ऽआहितम् ।
आपः । समुद्रः । उत्ऽशिष्टे । चन्द्रमाः । वातः । आऽहितः ॥ २ ॥

प्रथमयर्चा संग्रहेण उक्त एवार्थः एतदादिभिर्मन्त्रैर्बहुधा प्रपञ्च्यते । द्यावापृथिवी द्यावापृथिव्यौ उच्छिष्टे उच्छिष्यमाणे ब्रह्मणि तदात्मके हुतशिष्टौदने वा समाहिते । आश्रित्य वर्तेते इत्यर्थः । भूतम् तत्रत्यं यद् भूतजातं विश्वम् सर्वं तद् उच्छिष्टे समाहितम् सम्यग् निहितम् । तदाधारवशात् प्रचलतीत्यर्थः । तथा आपः व्यापनशीलाः प्रथमसृष्टा जगत्कारणभूताः तासां समुदायात्मकः समुद्रश्च तस्मिन् उच्छिष्टे समाहिताः । चन्द्रमाः तस्मात् समुद्रात् मथ्यमानाद् उत्पन्नः वातः वायुः अन्तरिक्षाधिपतिर्देवः आहितः आश्रितः ॥

1 S′ उच्छिष्यमाण॰.

तृतीया ॥

सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
लौक्या उच्छिष्ट आयत्ता[1] व्रश्च द्रश्चापि श्रीर्मयि ॥ ३ ॥

सन् । उत्ऽशिष्टे । असन् । च । उभौ । मृत्युः । वाजः । प्रजाऽपतिः ।
लौक्याः । उत्ऽशिष्टे । आऽयत्ताः[2] । व्रः । च । द्रः । च । अपि । श्रीः ।
मयि ॥ ३ ॥

सन् सत्तया क्रोडीकृतो भावरूपः प्रपञ्चः । असन् अभावात्मकश्च । उभौ सदसतौ उच्छिष्टे तस्मिन् उदीरितलक्षणे । कार्यत्वेन वर्तेते इत्यर्थः । तथा तस्य सदसदात्मकस्य प्रपञ्चस्य [मारको[1]] मृत्युः वाजः तदीयं बलं तस्य सर्वस्य स्रष्टा प्रजापतिश्च तत्रैव आहिताः । तथा लौक्याः लोकसंबन्धिन्यः प्रजाः तस्मिन् उच्छिष्टे आहिताः स्थापिताः । तथा व्रः वारको वरुणः द्रः द्रावकः अमृतमयः सोमः । परस्परसमुच्चयार्थौ चकारौ । तावपि अस्मिन् आहितौ । तत्प्रसादात् श्रीः संपत् मयि विदुषि आहिता आस्थिता भवतु ॥

चतुर्थी ॥

दृढो दृंह[3]स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥ ४ ॥

दृढः । दृंह[4]ऽस्थिरः । न्यः । ब्रह्म । विश्वऽसृजः । दश ।
नाभिम्ऽइव । सर्वतः । चक्रम् । उत्ऽशिष्टे । देवताः । श्रिताः ॥ ४ ॥

दृढः दृढाङ्गः । प्रवृद्धशरीरो देव इत्यर्थः । ⌛दृह दृहि वृद्धौ । "दृढः स्थूलबलयोः" इति निष्ठायां निपात्यते⌛ । दृंह[स्थिर]ः

१ K आयता. Dc आयता corrected to आयत्ता. We with A B B^h C D E K^m R S^m V Cs.
२ P^2 आऽयताः ।. We with P J Cp. ३ So A B^h B C D E K K^m R S^m P P^2 J V Cs Dc. See the next note. ४ P P^2 J दृंह । स्थिरः ।. Cp दृंहः । स्थिरः ।. We with Sâyaṇa's commentary. ५ So P P^2 J K Cp.

1 S′ सद followed by a blank space for three letters, in place of मारको.

दृंहणेन स्थिरीकृतो लोकः । न्यः नेतारस्तत्रत्याः प्राणिनः । ब्रह्म परिवृढं जगत्कारणम् अव्यक्तात्मकम् । विश्वसृजः विश्वस्य स्रष्टारो नव ब्रह्माणः तत्स्रष्टा [दशमः एवं] दशसंख्याकाः । यद्वा नव प्राणाः मुख्यः प्राण एकः । एते हि प्रथमसृष्टा विश्वस्य स्रष्टारः । एते सर्वे उच्छिष्टे समाहिताः । अपि च देवताः इन्द्राद्याः सर्वे देवा नाभिमिव चक्रम् यथा रथचक्रं मध्यस्थं नाभिं सर्वत आवेष्ट्य वर्तते एवम् उच्छिष्टे श्रिताः आश्रिताः । कारणभूतं ब्रह्म आवेष्ट्य वर्तन्त इत्यर्थः ॥

पञ्चमी ॥

ऋक् साम॒ यजु॒रुच्छि॑ष्ट उद्गी॒थः प्रस्तु॑तं स्तु॒तम् ।
हि॒ङ्का॒र उच्छि॑ष्टे॒ स्व॒रः साम्नो॑[1] मे॒डिश्च॒ तन्मयि॑ ॥ ५ ॥

ऋक् । साम॑ । यजुः॑ । उत्ऽशि॑ष्टे । उ॒त्ऽगी॒थः । प्रऽस्तु॑तम् । स्तु॒तम् ।
हि॒[2]ङ्ऽका॒रः । उत्ऽशि॑ष्टे । स्वरः॑ । साम्नः॑ । मे॒डिः । च॒ । तत् । मयि॑ ॥ ५ ॥

अनयोत्तरया च यज्ञाङ्गानां तदाश्रितत्वं प्रतिपाद्यते ऋक् साम यजुरिति । सर्वत्र जातावेकवचनम् । ऋचः पादबद्धा मन्त्रा यज्ञे याज्यानुवाक्यादिरूपेण विनियुक्ताः । सामानि प्रगीतमन्त्राः "आज्यैः स्तुवते" "पृष्ठैः स्तुवते" इत्येवं स्तोत्रसाधनत्वेन विनियुक्ताः । यजूंषि प्रश्लिष्टपठिता अनुष्ठेयार्थप्रकाशका मन्त्राः । तेषां लक्षणं जैमिनिराचार्योऽसूत्रयत् । "तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था" [जै°२.१.३५] "गीतिषु सामाख्या" [जै°२.१.३६] "शेषे यजुःशब्दः" [जै°२.१.३७] इति । एवं त्रिविधा मन्त्रा उच्छिष्टे उच्छिष्यमाणे ब्रह्मणि समाश्रिताः । तत्र आज्यादिस्तोत्रनिर्वर्तकानां साम्नां पञ्च भक्तयः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः प्रयोगशास्त्रेण कल्पिताः । तत्र च उद्गात्रा गीयमानो भाग उद्गीथः । प्रस्तुतम् प्रस्तोत्रा गीयमानः प्रस्तावाख्यो भागः । प्रस्तूयते स्तुतेः प्रारम्भः क्रियते अनेनेति प्रस्तुतम् । प्रपूर्वात् स्तौतेः करणे निष्ठा । स्तुतम् स्तोत्रं स्तवनकर्म । हिङ्कारः सर्वैरुद्गातृभिः आदौ

१ V मी॒डिश्च॒. २ P हि॒ग्°. We with P̊ J Cp.

प्रयुज्यमानो हिं इति शब्दः । स्वरः कृत्स्नसामाश्रितः क्रुष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रातिमन्द्रात्मकः सप्तविधः स्वरः । अथ वा कानिचित् सामानि आ इ ई इत्येवमात्मकैः स्वरैः परिसमाप्यन्ते । तानि च सामानि स्वरनिधनानि इत्युच्यन्ते । स आकारोत्र स्वरशब्देन विवक्षितः । स च साम्नः संबन्धी । तथा मेडिः मेलयिता ऋगक्षराणां गानविशेषस्य च संसर्जकः स्तोभविशेषः । अथ वा मेलि[1]रिति वाङ्नाम । साम्नः संबन्धिनी वाक् । कानिचित् सामानि वाङ्निधनानि गीयन्ते । तदभिप्रायम् एतत् । तद् एतद् उद्गीथादिकं सर्वम् उच्छिष्टे समाश्रितम् । तत् सर्वं मयि यज्ञसमृद्ध्यर्थं भवत्वित्यर्थः ॥

षष्ठी ॥

ऐ॒न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम् ।
उच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ॥ ६ ॥

ऐ॒न्द्रा॒ग्नम् । पा॒व॒मा॒नम् । म॒हाऽना॑म्नीः । म॒हा॒ऽव्र॒तम् ।
उत्ऽशि॑ष्टे । य॒ज्ञस्य॑ । अङ्गा॑नि । अ॒न्तः । गर्भः॑ऽइव । मा॒तरि॑ ॥ ६ ॥

ऐन्द्राग्नम् इन्द्राग्न्योः स्तावकम् "इन्द्राग्नी आ गतं सुतम्" इति तृचे [ऋ° ३.१२.१] गीयमानं साम ऐन्द्राग्नं प्रातःसवने प्रयुज्यमानम् । पावमानम् त्रिष्वपि सवनेषु सवनादौ गीयमानं पवमानसोमदेवताकं साम । उभयत्र "सास्य देवता" इति अण् प्रत्ययः । महानाम्नीः महानाम्न्यः । "विदा मघवन् विदा गातुम् अनुशंसिषो दिशः" [ऐ° आ° ४.१] इत्याम्नाता ऋचः । तत्र गीयमानं शाक्वरं सामापि महानाम्नीशब्देनोच्यते[2] । ताश्च द्वादशाहमध्यवर्तिनि दशरात्रे पञ्चमेऽहनि पृष्ठसामत्वेन विनियुक्ताः । महाव्रतम् राजनगायत्रबृहद्रथन्तरभद्राख्यैः पञ्चभिः सामभिः क्रियमाणं स्तोत्रम् । तच्च गवाम[3]यनस्योपान्त्येहनि प्रथमं पृष्ठस्तोत्रम् । एकाहोपि सोमयागस्तद्वान् महाव्र[4]तम् इति आख्यायते । एवम् ऐन्द्राग्नादीनि यज्ञस्य अङ्गानि उच्छिष्टे अन्तः मध्ये मातरि गर्भ इव वर्तन्ते । यथा मातुरुदरमध्ये आश्रितो गर्भः पुष्यन् अ-

1 S′ मेलेरिति. 2 S′ °नोच्यन्ते. 3 S′ omits °म°. 4 S′ °व्रत इति.

भिवर्धते एवम् एतान्यपि कारणभूते ब्रह्मणि आश्रितत्वेन भाव्यमानानि अङ्गिनं यज्ञं फलसमृद्धं कुर्वन्तीत्यर्थः ॥

सप्तमी ॥

राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः ।
अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥ ७ ॥

राजऽसूयम् । वाजऽपेयम् । अग्निऽस्तोमः । तत् । अध्वरः ।
अर्कऽअश्वमेधौ । उत्ऽशिष्टे । जीवऽबर्हिः । मदिन्ऽतमः ॥ ७ ॥

अङ्गवद् अङ्गिनामपि तदाश्रयत्वम् इतः परं प्रतिपाद्यते । राजा सूयते प्रेर्यते यस्मिन् कर्मणि तद् राजसूयम् इष्टिपशुसोमदर्विहोमात्मकं शस्त्रप्रधानम् । "राजसूयसूर्य°" इत्यादिना क्यपि निपात्यते । "गतिकारकोपपदात् कृत्" इति कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजपेयम् वाजः अन्नं द्रवीकृत्य पेयं यस्मिन् कर्मणि तत् तथोक्तम् । "राजा स्वर्गकामो राजसूयेन यजेत" इति [आश्व° ९. ९. १९] क्षत्रिय एव राजसूये कर्मणि अधिकारी । वाजपेये तु ब्राह्मणक्षत्रियौ उभावपि अधिक्रियेते । श्रूयते हि । "स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः । तं वा एतं वाजपेयम् इत्याहुः" इति [तै° ब्रा° १. ३. २. ३] । तथा अग्निष्टोमः चरमस्तोत्रे यज्ञायज्ञीये अग्निः स्तूयत इति अग्निष्टोमः द्वादशस्तोत्रशस्त्रसहितः सर्वसोमानां प्रकृतिभूतः सोमयागः । तत् । लिङ्गव्यत्ययः । सोध्वरः हिंसाप्रत्यवायरहितः । "अग्नीषोमीयं पशुम् आलभेत" इति [आ]लभ्यपशुहिंसाया विहितत्वेन "न हिंस्यात् सर्वभूतानि" इति निषेधशास्त्रस्य तत्रानुप्रवेशाभावात् । अर्काश्वमेधौ अर्कश्चित्योग्निः । अश्वो मेधः पशुर्यस्मिन् त्रिरात्रात्मके अहीने सोमे सोऽश्वमेधः । तौ अर्काश्वमेधौ । अथ वा विराडात्मना उपास्यमानश्चित्योग्निः अर्कः । तस्य च तथात्वेन उपासनम् ऐतरेयकोपनिषदि समाम्नायते । "एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते । एतमग्नावध्वर्यवः । एतं महाव्रते छन्दोगाः" इति [ऐ° आ°

१ B आर्काश्व°.

1 S′ शतप्रधानम्. 2 So S′. 3 S′ °स्तोत्रे. 4 S′ °षोमीयपशुं.

३.२.३]। अश्वमेधशब्देन च "उषा वा अश्वस्य मेध्यस्य शिरः" [बृ० आ० १.१.१] इत्याद्युपनिषदा अश्वमेधाङ्गस्य अश्वस्य विराडात्मना यद् उपासनम् उक्तं तद् विवक्षितम्। "तावेतावर्काश्वमेधौ" [बृ० आ० १.२.७] इति तदुपासनप्रकरणे समाम्नानात्। एतदेवाभिप्रेत्य तैत्तिरीयैरपि आम्नायते। "अर्को वा एष यद् अग्निः। असावादित्योऽश्वमेधः" इति [तै० सं० ५.७.५.२]। एते राजसूयादयः सर्वे उच्छिष्टे उच्छिष्यमाणे निष्प्रपञ्चे ब्रह्मणि तदात्मना भाव्यमाने ओदने वा समाश्रिताः। तथा जीवबर्हिः जीवावस्थान्येव बर्हींषि यस्य यागविशेषस्य स तथोक्तः। मदिन्तमः मादयितृतमः देवानां तृप्तिविशेषकरः अन्योपि सोमयागः। स सर्वोपि उच्छिष्टे समाश्रित इत्यर्थः। "नाद्घस्य" इति तमपो नुडागमः॥

अष्टमी॥

अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह।
उत्सन्ना यज्ञाः सत्त्राण्युच्छिष्टेधि समाहिताः॥ ८॥

अग्निऽआधेयम्। अथो इति। दीक्षा। कामऽप्रः। छन्दसा। सह।
उत्ऽसन्नाः। यज्ञाः। सत्त्राणि। उत्ऽशिष्टे। अधि। समऽआहिताः॥ ८॥

अग्न्याधेयम् अग्नयो गार्हपत्यादयो यस्मिन् कर्मणि आधीयन्ते तद् अग्न्याधेयम्। अथो अग्न्याधानानन्तरमेव सोमयागस्य या दीक्षा दीक्षणीयेष्ट्यादिरूपा कामप्रच्छन्दसा कामान् अभिलषितान् फलविशेषान् प्राति यजमानस्य पूरयतीति कामप्रम्। प्रा पूरणे। "आतोनुपसर्गे कः" इति कप्रत्ययः। तादृशेन छन्दसा गायत्रीत्रिष्टुबादिना सवननिष्पादकेन सह। उत्सन्नयज्ञाः[1] इदानीं दुरधिगमतया अनुष्ठानाभावात् लुप्तप्राया यज्ञा उत्सन्नयज्ञा इत्युच्यन्ते। तानेव निर्दिशति सत्त्राणीति। सी-

१ E कामः प्रः छंदसा. A C K K̈ V Dc कामप्रछन्दसा. B̈ कामपृछंदसा. D R B Cs कामप्रः छंदसा. S̈ कामः प्र छंदसा. We with the spirit of D R B Cs and with P P̈ J Cp. Sâyaṇa: कामप्रछन्दसा, one word. २ P कम° for काम°. We with P̈ J Cp. ३ P̈ सर्वाणि।. We with P J Cp.

1 Sâyaṇa's text too: उत्सन्नयज्ञाः सत्रा°.

दन्ति एषु बहवो यजमानाः कर्तृत्वेनेति बहुकर्तृकाः सोमयागाः सत्त्राणि उच्यन्ते । श्रूयते हि । "चतुर्विंशतिपरमाः सप्तदशावराः सत्त्रम् आसीरन्" इति । तानि च त्रयोदशरात्रप्रभृतीनि विश्वसृजाम् अयनान्तानि । न खल्विदानींतनानाम् अल्पमतीनाम् अल्पायुषां तदनुष्ठानं संभवतीति तेषाम् उत्सन्नयज्ञत्वम् । एवम् अनुक्रान्ता अग्न्याधेयादयः सर्वे यागा उच्छिष्टे ब्रह्मणि अधि समाहिताः समाश्रिताः ॥

नवमी ॥

अ॒ग्नि॒हो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑ ।
दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥ ९ ॥

अ॒ग्नि॒ऽहो॒त्रम् । च॒ । श्र॒द्धा । च॒ । व॒ष॒ट्ऽका॒रः । व्र॒तम् । तपः॑ ।
दक्षि॑णा । इ॒ष्टम् । पू॒र्तम् । च॒ । उत्ऽशि॑ष्टे । अधि॑ । स॒म्ऽआहि॑ताः ॥ ९॥

अग्नये होत्रं होमः अस्मिन् कर्मणि इति अग्निहोत्रम् "सायं प्रातरग्निहोत्रं जुहुयात्" इति [आप° ६.१५.१४] विहितम् । श्रद्धा श्रद्धानं तदनुष्ठानविषया आस्तिक्यबुद्धिः । ⌛"श्रदन्तरोरुपसर्गवद् वृत्तिरिष्यते" इति वचनात् "आतश्चोपसर्गे" इति अङ् । परस्परसमुच्चयार्थौ चकारौ⌛ । वषट्कारः याज्यान्ते हविःप्रदानाय प्रयुज्यमानो वौषट् इति शब्दः । व्रतम् । "नानृतं वदेत् । नास्य ब्राह्मणोनाश्वान् गृहे वसेत्" [तै° ब्रा° १.१.४.२] इत्यादिशास्त्रविहितम् आहिताग्नेः प्रातिस्विकम् अनृतवदनवर्जनादिरूपं कर्म

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।

इत्येवमादिरूपं वर्ज्यसाधारणं च व्रतशब्देन विवक्षितम् । तपः शरीरसंतापकरं कृच्छ्रचान्द्रायणादिकम् । यद्वा "पयो ब्राह्मणस्य व्रतम् यवागू राजन्यस्य आमिक्षा वैश्यस्य" इति [तै° आ° २.८.१] दीक्षादिवसेषु देहयात्रार्थं विहितं पयःपानादिकं व्रतम् । तपो ब्रह्मचर्यं चित्तैकाग्र्यं वा ।

मनसश्चेन्द्रियाणां चैकाग्र्यं तप उच्यते ।

इति स्मरणात् । दक्षिणा "तस्य द्वादशशतं दक्षिणा" इत्यादिशास्त्रेण

विहिता ऋत्विगानतये देयद्रव्यस्य क्लृप्तिः[1] । तथा[2] इष्टम् श्रुतिविहितं यागहोमादि कर्म । पूर्तम् स्मृतिपुराणाभिहितं वापीकूपतटाकदेवायतनारामादिनिर्माणम् । एते च अग्निहोत्रादयः सर्वे उच्छिष्टे उच्छिष्यमाणे प्रपञ्चासंस्पृष्टे ब्रह्मणि । ॥अधिः सप्तम्यर्थानुवादी॥ । समाहिताः समाश्रिताः ॥

दशमी ॥

एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।
ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥ १० ॥ (१९)

एकऽरात्रः । द्विऽरात्रः । सद्यःऽक्रीः । प्रऽक्रीः । उक्थ्यः ।
आऽउतम् । निऽहितम् । उत्ऽशिष्टे । यज्ञस्य । अणूनि । विद्यया ॥१०॥ (१९)

एकां रात्रिं व्याप्य वर्तमानः सोमयाग एकरात्रः । तथा द्वे रात्री व्याप्य वर्तमानः सोमयागो द्विरात्रः । द्विरात्रप्रभृतयः सोमयागा अहीना इत्युच्यन्ते । "द्विरात्रप्रभृतय उपरिष्टाद् अतिरात्रा अहीना एकादशरात्रात्" इति सूत्रितत्वात् । अतो नैषां सत्त्रेष्वन्तर्भाव इति पृथगुपादानम् । ॥ "अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः" इति समासान्तः अकारप्रत्ययः॥ । सद्यस्क्रीः* प्रक्रीः[3] इत्युभौ एकाहौ सोमयागविशेषौ । सद्यस्तदानीमेव क्रीयते सोमोस्मिन्निति सद्यःक्रीः । प्रक्रीशब्दोपि इत्थं निर्वक्तव्यः । उक्थ्यः अग्निष्टोमसंस्थात ऊर्ध्वभावीनि त्रीणि स्तुतशस्त्राणि उक्थसंज्ञकानि यस्य सन्ति स सोमयाग उक्थ्यः[4] । तद् एतद् एकरात्रादिकम् उच्छिष्टे उदीरितलक्षणे ओतम् आबद्धं निहितम् निक्षिप्तम् । वर्तत इत्यर्थः । इत्थं यज्ञस्य संबन्धीनि अणूनि सूक्ष्माणि रूपाणि विद्यया भावनया । तत्रैव कारणभूते ब्रह्मणि[5] निहितानीत्यर्थः[5] ॥

[इति] चतुर्थेनुवाके प्रथमं सूक्तम् ॥

1 S′ क्लृप्तिः. 2 S′ त for तथा. 3 S′ परिक्रीः. 4 S′ उक्थः. 5 S′ ब्रह्मणापितत्व---नीत्यर्थः.

द्वितीयसूक्ते प्रथमा ॥

चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।

षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥ ११ ॥

चतुःऽरात्रः । पञ्चऽरात्रः । षट्ऽरात्रः । च । उभयः । सह ।

षोडशी । सप्तऽरात्रः । च । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । ये । यज्ञाः । अमृते । हिताः ॥ ११ ॥

चतसृभी रात्रिभिरावर्त्यमानः सोमयागश्चतूरात्रः । एवं पञ्चरात्रषड्रात्रसप्तरात्रा व्याख्येयाः । उभय इत्यनेन चतूरात्रादीनां द्विगुणितत्वं विवक्षितम् । उभौ चतूरात्रलक्षणौ अवयवावस्य सः अष्टरात्र उभयः । एवं पञ्चरात्रो द्विगुणितो दशरात्रो भवति । षड्रात्रो द्विगुणितो द्वादशरात्र इत्येवम् अवगन्तव्यम् । सहशब्द एतेषां साहित्यम् आचष्टे । षोडशी उक्थ्यसंस्थात उपरि षोडशं षोडशसंख्यापूरकं स्तोत्रं शस्त्रं च यस्यास्ति स सोमयागः षोडशी । तन्निर्वचनम् एवम् आम्नायते । "यद् वाव षोडशं स्तोत्रं षोडशं शस्त्रं तेन षोडशी । तत् षोडशिनः षोडशित्वम्" इति [तै° सं° ६. ६. ११. १] । ये च अन्ये यज्ञा अमृते हिताः अमृतलक्षणफलजनने समर्थाश्चतूरात्रादयः सर्वे ते यज्ञा उच्छिष्टात् ब्रह्मौदनोच्छेषणाद् उच्छिष्यमाणात् जगत्कारणाद् ब्रह्मण एव वा जज्ञिरे जाता बभूवुः । ⌛जनी प्रादुर्भावे । "गमहन°" इति उपधालोपः । "द्विर्वचनेचि" इति स्थानिवत्त्वात् साच्कस्य द्विर्वचनम्⌛ ॥

द्वितीया ॥

प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।

साह्नातिरात्रावुच्छिष्टे द्वादशाहोपि तन्मयि ॥ १२ ॥

प्रतिऽहारः । निऽधनम् । विश्वऽजित् । च । अभिऽजित् । च । यः ।

साह्नऽअतिरात्रौ । उत्ऽशिष्टे । द्वादशऽअहः । अपि । तत् । मयि ॥१२॥

---

१ B चतुरात्रः. Dc चतूरात्रः changed to चतुरात्रः. We with A B^h C D E K K^m R S^m V Cs. २ P चतू°. We with P^2 J Cp.

उद्गीथभक्त्यनन्तरभाविनी प्रतिहर्त्रा उच्यमाना साम्नश्चतुर्थी भक्तिः प्रतिहारः । "उपसर्गस्य घञ्यमनुष्ये बहुलम्" इति सांहितिको दीर्घः । येन भागेन साम परिसमाप्यते तन्निधनम्[1] । तच्च सर्वैरुद्गातृभिर्वक्तव्यम् । विश्वजिदभिजितौ द्वौ सोमयागौ अग्निष्टोमसंस्थौ । साह्नातिरात्रौ । एकेन अह्ना समाप्यमानः सवनत्रयात्मकः सोमयागः साह्नः । रात्रिम् अतीत्य वर्तत इति अतिरात्रः एकोनत्रिंशत्स्तुतशस्त्रवान् सोमयागः । एते प्रतिहारादयः उच्छिष्टे ब्रह्मणि परिकल्पिताः । द्वादशाहोऽपि । द्वादशानाम् अह्नां समाहारो यस्मिन् क्रतौ स क्रतुर्द्वादशाहः । स च सत्राहीनात्मकः । सोपि तस्मिन् ब्रह्मणि आश्रितः । "राजाहःसखिभ्यः°" इति टच् समासान्तः । "न संख्यादेः समाहारे" इति अह्नादेशाभावः । यद् एतद् अनुक्रान्तं यज्ञजातं तत् सर्वं मयि भवत्विति प्रार्थना अवगन्तव्या ॥

तृतीया ॥

सूनृता संनतिः क्षेमः[१] स्वधोर्जामृतं सहः ।
उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥ १३ ॥

सूनृता । सम्ऽनतिः । क्षेमः[२] । स्वधा । ऊर्जा[३] । अमृतम् । सहः ।
उत्ऽशिष्टे । सर्वे । प्रत्यञ्चः । कामाः । कामेन । ततृपुः ॥ १३ ॥

सूनृता प्रियसत्यात्मिका वाक् । संनतिः फलस्य नतिः उपनतिः । तस्य उपनतस्य फलस्य परिरक्षणं क्षेमः । स्वधा पितॄणां संबन्धिनी तृप्तिकरी । यद्वा अन्ननामैतत् । सर्वप्राण्युपभोग्यम् अन्नम् । ऊर्जा प्राणस्य स्थापकं बलकरम् अन्नम् । ऊर्ज बलप्राणनयोः[2] । अस्मात् पचाद्यच् । अमृतम् देवोपभोग्यम् अमृतत्वप्रापकं पीयूषम् । सहः पराभिभवनक्षमं बलम् । एते सर्वे कामाः काम्यमानाः फलविशेषा उच्छिष्टे ब्रह्मणि आश्रिताः प्रत्यञ्चः आत्माभिमुखम् अञ्चन्तः प्राप्नुवन्तः

१ B क्षमः. K^m R S^m क्षेमः. We with A B^h C D E K V Cs Dc. २ P J क्षेमः ।. P^2 क्षमः ।. We with Cp. ३ P ऊर्जाम् ।. We with P^2 J Cp.

1 S′ तन्निधानम्. 2 S′ °प्राणयोः.

कामेन काम्यमानेन अभिलषितफलेन तातृपुः यजमानं तर्पयन्ति प्रीणयन्ति । तृप प्रीणने । "छन्दसि लुङ्लङ्लिटः" इति वर्तमाने लिट् ॥

चतुर्थी ॥

नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।
आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन्मयि ॥ १४ ॥
नव । भूमीः । समुद्राः । उत्ऽशिष्टे । अधि । श्रिताः । दिवः ।
आ । सूर्यः । भाति । उत्ऽशिष्टे । अहोरात्रे इति । अपि । तत् । मयि ॥१४॥

नव भूमीः नवखण्डात्मिकाः पृथिव्यः । समुद्राः सप्तसंख्याकाः । दिवः द्युलोका उपरितनाः । उच्छिष्टे अधि उच्छिष्यमाणे ब्रह्मणि श्रिताः आश्रिताः । सूर्यश्चायम् उच्छिष्टे उच्छिष्यमाणे स्वप्रकाशे परब्रह्मणि आश्रितः सन् आ भाति आसमन्ताद् दीप्यते । "तस्य भासा सर्वम् इदं विभाति" इति श्रुतेः [क० व० ५. १५] । अहोरात्रे अपि तद् आश्रित्य आभातः । तद् उक्तं सर्वं मयि भवत्विति ॥

पञ्चमी ॥

उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥ १५ ॥
उपऽहव्यम् । विषुऽवन्तम् । ये । च । यज्ञाः । गुहा । हिताः ।
बिभर्ति । भर्ता । विश्वस्य । उत्ऽशिष्टः । जनितुः । पिता ॥ १५ ॥

उपहव्यम् एतत्संज्ञं सोमयागम् । विषूवन्तम् । गवामयनाख्यस्य संवत्सरसत्त्रस्य मासषट्कात्मकयोः पूर्वोत्तरपक्षयोर्मध्ये एकविंशस्तोमकोनुष्ठेयः

---

१ B B^h P भूमिः. We with A C D E K K^m R S^m V P^2 J Cp Cs Dc. २ B E omit अ in अपि. Dc अपि changed to पि. We with A C D K K^m R S^m V Cs. ३ P P^2 J omit the visarga. Cp श्रिता corrected into श्रिताः, which we adopt. ४ D उपहव्यं. K K^m V उपहव्यं विषू°. Dc उपहव्यं विषू° changed to उपहव्यं विषू° We with A B B^h C E R S^m Cs. ५ P^2 Cp उपऽहव्यम् ।. We with P J.

सोमयागो विषूवान् तम् । ये चान्ये यज्ञा गुहा हिताः गुहाया निगूढा अज्ञायमाना वर्तन्ते तान् सर्वान् यज्ञान् अयम् उच्छिष्टः उच्छिष्यमाण ओदनः परमात्मा वा बिभर्ति धारयति पोषयति वा । कीदृशः स इति विशेष्यते । विश्वस्य सर्वस्य जगतो भर्ता । जनितुः जनयितुः स्वजनकस्य सवयज्ञानुष्ठातुः पिता पुण्यलोके तस्योत्पादकः । परमात्मपक्षे तु लोके यो जनयिता तस्य सर्वस्यापि पिता । सर्वे जनयितारोपि अस्मात् प्रथमम् उत्पद्य[1] ततः स्वकार्यं जनयन्तीत्यर्थः । ततः सर्वकारणकारणभूत इति भावः ॥

षष्ठी ॥

पिता जनितुरुच्छिष्टोसोः पौत्रः पितामहः ।
स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥ १६ ॥

पिता । जनितुः । उत्ऽशिष्टः । असोः । पौत्रः । पितामहः ।
सः । क्षियति । विश्वस्य । ईशानः । वृषा । भूम्याम् । अतिऽघ्न्यः ॥ १६ ॥

उच्छिष्टः हुतावशिष्ट ओदनः जनितुः जनयितुः स्वोत्पादकस्य पिता लोकान्तरे दिव्यशरीरस्य उत्पादकः । तथा असोः प्राणस्य पौत्रः । प्राणचलनात् शरीरस्य चलनं तेन च ओदनस्य पाक इति व्यवधानापेक्षया पौत्रत्वम् । तथा तस्यैव प्राणस्य अयं पितामहः । भाविस्वर्गभोगयोग्यस्य शरीरस्य तावद् अयं पिता । तस्य शरीरोत्पत्त्यनन्तरं तत्र प्राणसंचार इति भाविशरीरव्यवधानाद् भाविनः प्राणस्य अयं परंपरया उत्पादक इति पितामहत्वम् ॥ "अथात आदेशो नेति नेति" [बृ० आ० २. ३. ११] इति दृश्यप्रपञ्चनिषेधावधित्वेन उच्छिष्यमाणः परमात्मा यदा उच्छिष्टशब्दार्थः तदा एवं योजना । जनितुर्जनयितुः उत्पादकस्य प्राणिजातस्य उच्छिष्यमाणः परमात्मा पिता । स्वस्वकार्यम् उत्पादयतां सर्वेषाम् अयम् आद्यस्रष्टेत्यर्थः । तथा असोः प्राणस्य प्रथमसृष्टस्य हिरण्यगर्भात्मनः पौत्रः । पुत्रश्चतुर्मुखो ब्रह्मा तत्सृष्टा देवादयः पौत्राः । तदात्मना परमात्मैव अवस्थित इत्यर्थः । तत्र यः पितामहो हिरण्यगर्भः तस्य च पर-

1 S′ उत्पाद्य.

मात्मनश्च वास्तवभेदाभावात् पितामहत्वमपि विज्ञेयम् । एवंभूतः स उच्छिष्टः विश्वस्य सर्वस्य जगत ईशानः ईश्वरो भवन् वृषा कामानां वर्षिता अतिघ्न्यः अतिक्रान्तहननः सन् भूम्याम् पृथिव्यां क्षियति निवसति । सर्वप्राणिशरीरेषु वर्तते ॥

सप्तमी ॥

ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।
भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥ १७ ॥

ऋतम् । सत्यम् । तपः । राष्ट्रम् । श्रमः । धर्मः । च । कर्म । च ।
भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मीः । बलम् । बले ॥१७॥

ऋतम् मनसा यथार्थसंकल्पनम् । सत्यम् वाचा यथार्थभाषणम् । तपः शरीरसंतापकरो व्रतोपवासादिनियमविशेषः । राष्ट्रम् राज्यम् । श्रमः शान्तिः शब्दादिविषयोपभोगस्य उपरतिः । धर्मः तज्जन्यः अपूर्वविशेषः । कर्म वर्णाश्रमानुसारेण विहितं यागदानहोमादि । भूतम् उत्पन्नं जगत् । भविष्यत् उत्पत्स्यमानम् । एतत् सर्वम् उच्छिष्टे ब्रह्मणि तदात्मके[1] ओदने वा कार्यत्वेन नित्यम् आश्रितम् इति । तथा वीर्यम् सामर्थ्यम् । लक्ष्मीः सर्ववस्तुसंपत्तिः । बलम् सर्वकर्मनिर्वर्तनक्षमं[2] शरीरगतं सामर्थ्यं बले बलवति तस्मिन् उच्छिष्टे । वर्तन्त इत्यर्थः ॥

अष्टमी ॥

समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।
संवत्सरोध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥ १८ ॥

समऽऋद्धिः । ओजः । आऽकूतिः । क्षत्रम् । राष्ट्रम् । षट् । उर्व्यः ।
समऽवत्सरः । अधि । उत्ऽशिष्टे । इडा । प्रऽएषाः । ग्रहाः । हविः ॥१८॥

समृद्धिः इष्टफलस्य अभिवृद्धिः । ओजः शारीरबलम् अष्टमो धातुः । आकूतिः इष्टफलविषयः संकल्पः । क्षत्रम् क्षात्रं तेजः । राष्ट्रम् क्षत्रधर्मेण परिपालनीयं राज्यम् । षट् षट्संख्याका उर्व्यः । ताश्च मन्त्रान्तरे

1 S′ omit °त्मके. 2 S′ °निवर्तनक्षमं.

परिगण्यन्ते । "षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च" इति [आश्व° १.२.१] । तथा संवत्सरः द्वादशमासात्मकः कालः । इडा नाम देवता यस्याः प्रीतये यज्ञेषु हुतशिष्टात् पुरोडाशादेर्भागोवदीयते । प्रैषाः कर्मसु ऋत्विजां प्रेरका मन्त्राः । ग्रहाः वायव्यैर्गृह्यमाणा ऐन्द्रवायवादयः सोमाः । हविश्चरुपुरोडाशादिलक्षणम् । एतत् सर्वम् उच्छिष्टे [अधि] उच्छिष्यमाणे ब्रह्मणि आधारे । वर्तत इत्यर्थः ॥

नवमी ॥

चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।
उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः[१] ॥ १९ ॥
चतुःऽहोतारः । आप्रियः । चातुःऽमास्यानि । निऽविदः ।
उत्ऽशिष्टे । यज्ञाः । होत्राः । पशुऽबन्धाः । तत् । इष्टयः[१] ॥ १९ ॥

चतुर्होतारः चतुर्होतृसंज्ञका मन्त्राः "चित्ति स्रुक्" इत्याद्याः पञ्चानुवाकास्तैत्तिरीयके [तै° आ° ३.१-५] समाम्नाताः । यद्यपि तेषां दशहोता चतुर्होता [पञ्चहोता] षड्ढोता सप्तहोतेति क्रमेण संज्ञा तथापि ते सर्वे चतुर्होतृसंज्ञयैवोच्यन्ते । तथा च तत्रैव होतृविध्यवसाने श्रूयते । "त्वं वै "मे नेदिष्ठं हूतः प्रत्यश्रौषीः । त्वं[1] वै नानाख्यातार इति । तस्मान्नु हैनां- "श्चतुर्होतार इत्याचक्षते" इति [तै° ब्रा° २.३.११.४] । आप्रियः पशुयागसंबन्धिनां प्रयाजानां याज्याः । श्रूयते हि तन्नामनिर्वचनम् । "आप्रीभिराप्नुवन् तद् आप्रीणाम् आप्रित्वम्" इति [तै° ब्रा° २.२.८.६] । भगवान् आश्वलायनोपि सूत्रयति स्म । "एकादश प्रयाजाः । तेषां प्रैषाः । "प्रथमं प्रैषसूक्तम् । अध्वर्युप्रेषितो मैत्रावरुणः प्रैष्यति[2] । प्रैषैर्होतारम् । "होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः" इति [आश्व° ३.२.१-५] । चातुर्मास्यानि चतुर्षु मासेषु क्रियमाणानि वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यानि चत्वारि पर्वाणि "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इति [श° प° २.६.३.१, आप° ८.१.१] श्रुत्या विहितानि । नि-

१ So we read with A B B^h C D E K K^m R S^m P P^2 J V Cs Dc.

1 S′ त्वयैनाना° for त्वं वै नाना°. 2 So S′.

विदः स्तोतव्यगुणप्रकर्षनिवेदनपरा मन्त्राः "अग्निर्देवेद्धः । अग्निर्मन्विद्धः । इन्द्रो मरुत्वान्त्सोमस्य पिबतु । इन्द्रो देवः सोमं पिबतु" [निवि॰ १. १-३] इत्येवमाद्याः । "निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्" इति हि [ऐ॰ ब्रा॰ ३. ९] ब्राह्मणम् । तथा यज्ञा यागाः । होत्राः होतृप्रमुखाः सप्त वषट्कर्तारः । पशुबन्धाः अग्नीषोमीयसवनीयानुबन्ध्यात्मकाः सोमाङ्गभूताः पशुयागाः । स्वतन्त्राश्च "वायव्यं श्वेतम् आलभेत" [तै॰ सं॰ २. १. १. १] इत्यादिना विहिताः । इष्टयोपि अङ्गभूताः स्वतन्त्राश्च । तद् एतद् अनुक्रान्तं चतुर्होतृप्रभृतिकं सर्वम् उच्छिष्टे उच्छिष्यमाणे ब्रह्मणि तदात्मके ओदने [वा] समाश्रित्य वर्तत इत्यर्थः ॥

दशमी ॥

अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।
उच्छिष्टे घोषिणीरापः[1] स्तनयित्नुः श्रुतिर्मही ॥ २० ॥ (२०)

अर्धऽमासाः । च । मासाः । च । आर्तवाः । ऋतुऽभिः । सह ।
उत्ऽशिष्टे । घोषिणीः[3] । आपः । स्तनयित्नुः । श्रुतिः[4] । मही ॥ २० ॥

अर्धमासाः पञ्चदशदिवसात्मकाः पक्षाः । मासाश्चैत्राद्याः । आर्तवाः तत्तदृतुसंबन्धिनः पदार्थविशेषाः । ऋतुभिः तैर्वसन्ताद्यैः सह । सर्वे एते उच्छिष्टे समाश्रिताः । तथा घोषिणीः घोषिण्यः घोषयुक्ता आपः । स्तनयित्नुः स्तनयन् गर्जितं कुर्वन् मेघः । शुचिः[*] शुद्धा मही महती भूमिः । एतेपि तस्मिन् उच्छिष्टे । समाश्रिता इत्यर्थः ॥

[इति] चतुर्थेनुवाके द्वितीयं सूक्तम् ॥

तृतीयसूक्ते प्रथमा ॥

शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।
अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता[5] ॥ २१ ॥

---

१ D E K̈ R S̈ V Cs omit the visarga. We with A B̈ C K Dc. २ K V शुचि°. We with A B B̈ C D E K K̈ R Dc S̈ P̈ J. ३ P घोषर्णीः।. We with P̈ J Cp. ४ P शुतिः।. We with P̈ J Cp. ५ So A B B̈ C D E K K̈ R S̈ P P̈ J V Cs Dc, without the visarga.

शर्कराः । सिकताः । अश्मानः । ओषधयः । वीरुधः । तृणा ।
अभ्राणि । विऽद्युतः । वर्षम् । उत्ऽशिष्टे । सम्ऽश्रिता । श्रिता ॥ २१ ॥

शर्कराः क्षुद्रपाषाणविशेषाः । सिकताः वालुकाः । अश्मानः पाषाणाः । ओषधयः व्रीहियवाद्याः । वीरुधः विरोहणशीला लताः । तृणा तृणानि गवादिभिरुपभोग्यानि । अभ्राणि उदकपूर्णा मेघाः । विद्युतस्तडितः । वर्षम् वृष्टिः । एते सर्वे उच्छिष्टे संश्रिता* समवस्थिताः । श्रिता*ः इति पुनरुक्तिरादरार्था । यद्वा ये च अन्ये संश्रिताः स्वाश्रयसमवेताः पदार्थास्ते सर्वे श्रिता इति ॥

द्वितीया ॥

राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः[1] ।
अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥ २२ ॥

राद्धिः । प्रऽआप्तिः । सम्ऽआप्तिः । विऽआप्तिः । महः । एधतुः ।
अतिऽआप्तिः । उत्ऽशिष्टे । भूतिः । च । आऽहिता । निऽहिता । हिता ॥२२॥

राद्धिः संसिद्धिः सम्यग् निष्पत्तिः । प्राप्तिः प्रेप्सितस्य फलस्य अधिगमः । समाप्तिः सम्यग् आप्तिः । व्याप्तिः विविधा आप्तिः । महः तेजः उत्सवो वा । एधतुः अभिवृद्धिः । अत्याप्तिः अतिक्रान्ता आप्तिः । भूतिः समृद्धिः । सा च आहिता आभिमुख्येन स्थिता निहिता निक्षिप्ता । अत्र सर्वत्र उपसर्गवशाद् अर्थभेदोवगन्तव्यः । राद्ध्यादयः सर्वास्तस्मिन् उच्छिष्टे हिता*ः स्थिताः ॥

तृतीया ॥

यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ २३ ॥

यत् । च । प्राणति । प्राणेन । यत् । च । पश्यति । चक्षुषा ।
उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवाः । दिविऽश्रितः ॥ २३ ॥

---

१ A B B[h] C D E K K[m] R S[m] V Cs Dc एधतुः. P[2] J Cp एधतुः. We with P.

यच्च प्राणिजातं प्राणेन प्राणवायुना प्राणति प्राणनव्यापारं करोति यद्वा प्राणेन घ्राणेन्द्रियेण प्राणति गन्धान् आजिघ्रति यच्च प्राणिजातं चक्षुषा चक्षुरिन्द्रियेण पश्यति नीलपीतादिकं साक्षात्करोति ते सर्वे प्राणिनः उच्छिष्टात् उच्छिष्यमाणाद् ब्रह्मणः सकाशात् जज्ञिरे । तथा दिविश्रितः द्युलोके स्थिताः । ⌛श्रिञ् सेवायाम् । "क्विप् च" इति क्विप् । "तत्पुरुषे कृति बहुलम्" इत्यत्र "हृद्द्युभ्यां ङेरुपसंख्यानम्" इति अलुक्⌛ । ये च अन्ये दिवि द्युलोके वर्तमाना देवास्ते सर्वे उच्छिष्टाज्जज्ञिरे ॥

चतुर्थी ॥

ऋचः सामा॑नि॒ च्छन्दां॑सि पु॒राणं॒ यजु॑षा स॒ह ।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रित॑ः ॥ २४ ॥

ऋच॑ः । सामा॑नि । छन्दां॑सि । पु॒राण॑म् । यजु॑षा । स॒ह ।
उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । दि॒वि । दे॒वाः । दि॒वि॒ऽश्रित॑ः ॥ २४ ॥

उच्छिष्टाज्जज्ञिर इति उत्तरोर्धर्चः अनुषज्यते । ऋचः पादबद्धा मन्त्राः । सामानि गीतविशिष्टा मन्त्राः । छन्दांसि गायत्र्युष्णिगादीनि चतुरक्षराधिकानि सप्तसंख्याकानि । पुराणम् पुरातनवृत्तान्तकथनरूपम् आख्यानम् । यजुषा यजुर्मन्त्रेण सह उच्छिष्टाज्जज्ञिरे । शेषं पूर्ववत् ॥

पञ्चमी ॥

प्रा॒णा॒पा॒नौ चक्षु॒ः श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या ।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रित॑ः ॥ २५ ॥

प्रा॒णा॒पा॒नौ । चक्षु॑ः । श्रोत्र॑म् । अक्षि॑तिः । च॒ । क्षिति॑ः । च॒ । या ।
उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । दि॒वि । दे॒वाः । दि॒वि॒ऽश्रित॑ः ॥ २५ ॥

प्राणापानौ प्राणवृत्तिः अपानवृत्तिश्च । चक्षुः रूपदर्शनसाधनम् इन्द्रियम् । श्रोत्रम् शब्दग्रहणसाधनम् इन्द्रियम् । अक्षितिः क्षयाभावः । या च क्षितिः क्षयः । यद्वा अक्षितिः अक्षीयमाणा देवता । क्षितिः क्षयाभिमानिनी । एते सर्वे पदार्था उच्छिष्टाज्जज्ञिरे इति ॥

षष्ठी ॥

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ २६ ॥

आऽनन्दाः । मोदाः । प्रऽमुदः । अभिमोदऽमुदः । च । ये ।
उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवाः । दिविऽश्रितः ॥ २६ ॥

आनन्दाः विषयोपभोगजनिताः सुखविशेषाः । मोदाः विषयदर्शनजन्या हर्षाः । मुद हर्षे इत्यस्माद् भावे घञ् । प्रकृष्टा मुदः प्रमुदः प्रकृष्टविषयलाभजन्या हर्षाः । ये च अभीमोदमुदः आभिमुख्येन वर्तमानो मोदः अभिमोदः । "उपसर्गस्य घञ्यमनुष्ये बहुलम्" इति दीर्घः । अभिमोदेन मोदयन्ति हर्षयन्तीत्यभिमोदमुदः संनिहिताः सुखहेतवः पदार्थाः । ते सर्वे उच्छिष्टाज्जज्ञिरे इति ॥

सप्तमी ॥

देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ २७ ॥ (२१)

देवाः । पितरः । मनुष्याः । गन्धर्वऽअप्सरसः । च । ये ।
उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवाः । दिविऽश्रितः ॥ २७ ॥

देवाः अष्टौ वसव एकादश रुद्रा इत्येवं गणशो वर्तमानाः । पितरः पितृलोकनिवासिनः पूर्वपुरुषाः । मनुष्याः मनोः सकाशाद् उत्पन्ना मनुष्यजात्याक्रान्ताः । "मनोर्जातावञ्यतौ षुक् च" इति मनुशब्दाद् यत् प्रत्ययः षुगागमश्च । "तित् स्वरितः" इति स्वरितत्वम् । गन्धर्वाप्सरसः गन्धर्वाः विश्वावसुप्रभृतयः । अप्सरसः उर्वशीप्रभृतयः । ये च एते देवाद्या अनुक्रान्तास्ते सर्वे उच्छिष्टात् ब्रह्मौदनोच्छेषणाद् उच्छिष्यमाणाद् ब्रह्मणः सकाशाद् वा जज्ञिरे उत्पन्नाः । तथा दिवि द्युलो-

---

१ P मोदः ।. We with P[2] J Cp. २ P[2] °मदः ।. We with P J Cp.

के वर्तमाना ये च अन्ये देवाः तथा दिविश्रितः दिवम् आश्रित्य वर्तमाना देवजनाः ते सर्वे उच्छिष्टाज्जज्ञिरे इति ॥

[इति] चतुर्थेनुवाके तृतीयं सूक्तम् ॥

"यन्मन्युर्जायाम्" इत्यादिसूक्तत्रयम् अर्थसूक्तम् । अस्य सूक्तत्रयस्य ब्रह्मयज्ञजपे विनियोगः । अनेन च सूक्तत्रयेण षाट्कौशिकस्य शरीरस्य मध्ये आत्मत्वेन प्रविष्टं ब्रह्म उपदेक्ष्यन् उपलब्ध्यधिकरणभूतस्य तस्य शरीरस्य तत्साधनभूतानाम् इन्द्रियाणां च देवानां प्रश्नप्रतिवचनरूपेण उत्पत्तिम् अभिधित्सुस्तदुपायभूतां सृष्टिं प्रश्नप्रतिवचनाभ्याम् उपोद्घातयति "यन्मन्युः" इति द्व्यृचेन ॥

तत्र प्रथमा ॥

यन्मन्युर्जायामावहत् संकल्पस्य गृहादधि ।
क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत् ॥ १ ॥

यत् । मन्युः । जायाम् । आऽअवहत् । सम्ऽकल्पस्य । गृहात् । अधि ।
के । आसन् । जन्याः । के । वराः । कः । ऊं इति । ज्येष्ठऽवरः । अभवत् ॥ १ ॥

स्वमहिमप्रतिष्ठस्य परब्रह्मणः सत्त्वरजस्तमोगुणात्मिकाया मायाशक्तेश्च प्राणिकर्मपरिपाकजनितसंबन्धवशाज्जायमाना "सोकामयत बहु स्यां प्रजायेय" [तै° आ° ८. ६] इत्यादिश्रुतिप्रतिपाद्या या पारमेश्वरी[1] सिसृक्षावस्था सा[2] लौकिकविवाहत्वेन रूप्यते । यत् यदा मन्युः मन्यते सर्वं जानातीति मन्युः निरावरणज्ञान ईश्वरः । अत एव तस्य सर्वदेवतात्मकत्वम् आम्नायते । "मन्युर्भगो मन्युरेवास देवो मन्युर्होता वरुणो विश्ववेदाः" [तै° ब्रा° २. ४. १. ११] इति । ⌛मन ज्ञाने इत्यस्माद् औणादिको युप्रत्ययः⌛ । स जायाम् आवहत् जायतेस्यां सर्वं जगद् इति जाया सिसृक्षावस्थापन्ना पारमेश्वरी[1] मायाशक्तिः । ताम् आभिमुख्यं प्रापयत् । भार्यात्वेन[3] अभ्यमन्यतेत्यर्थः[3] । लोके हि जाया कस्यचित् श्वशुरस्य गृहाद् आनीयते । तद् दर्शयति संकल्पस्येति । "सो-

1 S′ परमेश्वरी. 2 S′ omit सा लौ°. 3 S′ भार्यात्वेन नाभ्यमन्यते°.

कामयत बहु स्यां प्रजायेय" इति [तै॰आ॰८.६] प्राथमिक ईश्वरकृतः संकल्पः । तस्य गृहाद् आवासात् । तद्वशादेव हि एषा सिसृक्षावस्था समजायत इत्येवं व्यपदिश्यते । अधिः पञ्चम्यर्थानुवादी । तदा तस्मिन् जायाया आवहने जन्याः जनसंबन्धिनो बान्धवा वधूवरपक्षीयाः के आसन् । सृष्टेः प्राक् कस्यचिदपि अभावाद् एवं प्रश्नः । के वा वराः कन्यावरणस्य कर्तारः । को नाम तस्मिन् समये ज्येष्ठवरः प्रधानभूतो वरः उद्वाहकर्ता अभवत् ॥

द्वितीया ॥

तप॑श्चै॒वास्ता॒ं कर्म॑ चा॒न्तर्म॑ह॒त्य॑र्ण॒वे ।
त आ॑सं॒ जन्या॒स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रो॑ऽभवत् ॥ २ ॥

तपः॑ । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्तः । म॒ह॒ति । अ॒र्ण॒वे ।
ते । आ॒स॒न् । जन्याः॑ । ते । व॒राः । ब्रह्म॑ । ज्ये॒ष्ठ॒ऽव॒रः । अ॒भ॒व॒त् ॥ २ ॥

तस्मिन् सृष्टिसमये स्रष्टुः परमेश्वरस्य तपः स्रष्टव्यपर्यालोचनात्मकम् । "यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः" इति श्रुतेः [मु॰१.१.९] । तस्य कर्म च प्राणिभिरनुष्ठितं पुण्यापुण्यात्मकं सुखदुःखफलोन्मुखं परिपक्वं कर्म च आस्ताम् अभवताम् । एवकारेण तदुभयव्यतिरिक्तस्य सत्ता निवार्यते । तपःकर्मणी एव सम्यगुपकरणत्वेन तस्मिन् समये अवस्थिते इत्यर्थः । श्रूयते हि । "तपसा चीयते ब्रह्म" [मु॰१.१.८] । "स तपोतप्यत । स तपस्तप्त्वा इदं सर्वम् असृजत" इति [तै॰आ॰८.६] । तपःकर्मणोः सत्ताया आधारं निर्दिशति । महति प्रभूते अर्णवे समुद्रे प्रलयकालीने अन्तः मध्ये । "आपो वा इदम् अग्रे सलिलम् आसीत्" इति हि [तै॰ब्रा॰१.१.३.५] ब्राह्मणम् । अर्णांसि उदकानि विद्यन्ते अस्मिन् इति अर्णवः । "अर्णसो लोपश्च" इति मत्वर्थीयो वकारः सलोपश्च । अनयोरेव तपःकर्मणोर्वस्त्वन्तराभावाद् व्यक्तिबाहुल्यबहुत्वम् उपचर्य कृतस्य प्रश्नस्य प्रतिवचनं त आसं जन्या इति । नि-

१ P P[2] J आस्तांम् ।. We with Cp. २ P J म॒ह॒ति॑ ।. We with P[2] Cp.

1 S′ लोचनयात्मकम्. 2 S′ सत्युपकरणत्वेन. 3 S′ omit °त्व°.

र्दिश्यमानप्रतिनिर्दिश्यमानयोः एकताम् आपादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गताम् उपाददत इति न्यायेन त इति प्रतिनिर्दिश्यमानापेक्षं पुंलिङ्गत्वम् ॥ । तास्तपःकर्मव्यक्तयो जन्याः विवाहप्रवृत्ता बन्धुजना आसन् । त एव वराः वरयितारश्च आसन् । यत् सिसृक्षावस्थं जगत्कारणं ब्रह्म मायाशक्तिरूपाया [जायाया] आवहने स एव ज्येष्ठवरः अभवत् । प्रधानभूत उद्वाहकर्ताभवद् इत्यर्थः ॥

तृतीया ॥

दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा ।
यो वै तान् वि॒द्यात् प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद् व॑देत् ॥ ३ ॥

दश॑ । सा॒कम् । अ॒जा॒य॒न्त॒ । दे॒वाः । दे॒वेभ्यः॑ । पु॒रा ।
यः । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । सः । वै । अ॒द्य । म॒हत् ।
व॒दे॒त् ॥ ३ ॥

यद् ब्रह्म सशक्तिकम् अभवद् इत्युक्तं तस्मात् सकाशाद् देवेभ्यः अधिष्ठातृभ्यः अग्न्यादिभ्यः पुरा तेषाम् उत्पत्तेः प्रागेव दशसंख्याका देवाः दीव्यन्ति स्वस्वविषयं प्रकाशयन्तीति देवा ज्ञानकर्मेन्द्रियाणि । यद्वा सप्त शीर्षण्याः प्राणा द्वौ अवाञ्चौ मुख्यः प्राण एक इति दश । अथ वा "प्राणापानौ चक्षुः श्रोत्रम्" इत्युत्तरत्र वक्ष्यमाणा दशसंख्याका देवाः साकम् सह अजायन्त । श्रूयते हि ।

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । इति [मु॰ २. १. ३] यो वै यः खलु उपासकः तान् देवान् प्रत्यक्षं विद्यात् अपरोक्षं जानीयात् स खलु विद्वान् अद्य इदानीं महत् देशकाल[2]कृतपरिच्छेदरहितं सर्वगतं ब्रह्म वदेत् उपदिशेत् ॥

चतुर्थी ॥

प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या॑ ।

१ B ये. We with A B^h C D E K K^m R S^m V Cs Dc.

1 S' उपपादत. 2 S' देशकालवकृत°.

व्यानोदानौ वाङ् मनस्ते वा आकूतिमावहन् ॥ ४ ॥

प्राणापानौ । चक्षुः । श्रोत्रम् । अक्षितिः । च । क्षितिः । च । या ।

व्यानऽउदानौ । वाक् । मनः । ते । वै । आऽकूतिम् । आ । अवहन् ॥ ४ ॥

हृदम्बुजमध्ये अवस्थितस्य क्रियाशक्त्यात्मकस्य मुख्यप्राणस्य प्राणापानाद्या [वृत्तयः । चक्षुः दर्शनसाधनम्] इन्द्रियम् । श्रोत्रम् शब्दग्रहणसाधनम् इन्द्रियम् । अक्षितिः अक्षीयमाणा ज्ञानशक्तिः । क्षितिः क्षीयमाणा निवासहेतुभूता वा क्रियाशक्तिः । ज्ञानशक्तिर्हि आत्मस्वरूपत्वेन नित्यत्वाद् न कदाचित् क्षीयते । क्रियाशक्तिस्तु अपवर्गसमये लिङ्गशरीरेण सह निवर्तत इति क्षितिशब्दाभिधेया । ॥ परस्परसमुच्चयार्थौ चकारौ ॥ । या एवंविधा द्विविधा शक्तिः । अस्तीत्यर्थः । व्यानोदानौ अन्नरसं[1] सर्वासु नाडीषु विविधम् अनिति प्रेरयतीति व्यानः । उत् ऊर्ध्वम् अनिति उद्गारादिव्यापारं करोतीति उदानः । एते प्राणस्य द्वे वृत्ती । वाक् वदनसाधनम्[2] इन्द्रियम् । मनः सर्वेन्द्रियानुग्राहकं सुखादिज्ञानसाधनम् अन्तःकरणम् । त एते प्राणापानादयो दश देवाः आकूतिम् पुरुषकृतं संकल्पम् आवहन् आभिमुख्येन प्रापयन्ति । पुरुषस्य अभिमतम् अर्थं निष्पादयन्तीत्यर्थः ॥

पञ्चमी ॥

अजाता[1] आसन्नृतवोथो धाता बृहस्पतिः ।

इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥ ५ ॥

अजाताः । आसन् । ऋतवः । अथो इति । धाता । बृहस्पतिः ।

इन्द्राग्नी इति । अश्विना । तर्हि । कम् । ते[2] । ज्येष्ठम् । उप । आसत ॥ ५ ॥

ऋतवः वसन्ताद्याः कालविशेषास्तस्मिन् सृष्टिसमये अजाता आसन् अनुत्पन्ना अभवन् । अथो अपि च धाता एतत्संज्ञकः अदितेः पुत्रः । बृहस्पतिः बृहतां देवानां पतिः सुरगुरुः । इन्द्राग्नी । अश्विना अश्विनौ

१ B आजाता. We with A B̊ C D E K K̊ R S̊ V Cs Dc. २ P ते. We with P̊ J Cp.

1 S′ inserts विविधं after अन्नरसं. 2 S′ अणिवदन° for वदन°.

एतत्संज्ञौ देवौ । एते षड् देवा ऋतूनाम् अधिपतयः । तेपि तस्मिन् समये अजाता अभवन् । एवं तर्हि तस्मिन् काले ते धात्रादयः स्वोत्पत्त्यर्थं ज्येष्ठम् वृद्धतमं कारणभूतं कं जनयितारम् उपासते[1]* अभ्यर्थयन्ते । अस्य प्रश्नस्य उत्तरम् अनन्तरभाविनी ऋक् ॥

षष्ठी ॥

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
तपो ह जज्ञे कर्मणस्तत् ते ज्येष्ठमुपासत ॥ ६ ॥

तपः । च । एव । आस्ताम् । कर्म । च । अन्तः । महति । अर्णवे ।
तपः । ह । जज्ञे । कर्मणः । तत् । ते । ज्येष्ठम् । उप । आसत ॥ ६ ॥

पूर्वोर्धर्चो व्याख्यातः । तत्र जगत्स्रष्टुरीश्वरस्य स्रष्टव्यपर्यालोचनात्मकं तपः कर्मणः कल्पान्तरे प्राणिभिरनुष्ठितात् पुण्यापुण्यात्मकात् परिपक्वात् कर्मणः सकाशात् जज्ञे । स्वमहिमप्रतिष्ठस्य असङ्गोदासीनस्य सृष्ट्युन्मुखत्वं प्राणिकर्मपरिपाककृतम् इति तदीयस्य तपसोपि कर्मैव कारणम् इत्यर्थः । अतस्ते धात्रादयो ज्येष्ठम् वृद्धतमं सृष्टेः कारणभूतं परिपक्वं स्वकृतं [तत्] कर्म उपासते* स्वोत्पादनाय प्रार्थयन्ते । देवमनुष्यादिरूपस्य सर्वस्य जगतः कर्मैव मूलकारणम् इत्यर्थः ॥

सप्तमी ॥

येत आसीद् भूमिः पूर्वा यामद्धातय इद् विदुः ।
यो वै तां विद्यान्नामथा स मन्येत पुराणवित् ॥ ७ ॥

या । इतः । आसीत् । भूमिः । पूर्वा । याम् । अद्धातयः । इत् । विदुः ।
यः । वै । ताम् । विद्यात् । नामऽथा । सः । मन्येत । पुराणऽवित् ॥ ७ ॥

१ $\overset{2}{P}$ J आस्तांम्. We with P Cp. २ P महति ।. We with $\overset{2}{P}$ J Cp. ३ P जन्ये ।. ४ $\overset{2}{P}$ आसते ।. We with P J Cp. ५ C D E K $\overset{m}{S}$ V तान्विद्या°. Cs तांन्विद्या°. We with A R $\overset{2}{P}$ J. ६ K पुराणवत्. We with A B $\overset{h}{B}$ C D E $\overset{m}{K}$ R $\overset{m}{S}$ P $\overset{2}{P}$ J V. ७ P Cp तान् ।. We with $\overset{2}{P}$ J.

1 S′ उपासत अभ्य°. But Sâyaṇa's text in S′ : उपासते.

इतः अस्याः पुरोवर्तिन्या भूमेः पूर्वा पूर्वभाविनी अतीतकल्पस्था या भूमिः आसीत् अभवत् । यां पूर्वां भूमिम् अद्धातयः अद्धा प्रत्यक्षम् अतन्ति व्याप्नुवन्ति इति अद्धातयः तपःप्रभावसमासादितसार्वज्ञ्याः[1] अतीतानागतज्ञा महर्षयः । इच्छब्दः अवधारणे । त एव विदुः जानन्ति । नान्ये । ताम् अतीतकल्पस्थां भूमिं यो वै यः खलु नामथा नामप्रकारेण तस्यां यद्यद् वस्त्वस्ति तत् सर्वं नामग्राहं विद्यात् जानीयात् । ॥ नामशब्दात् छान्दसस्थाल् प्रत्ययः ॥ । पुराणवित् पुरातनस्य अर्थस्य वेदिता स विद्वान् मन्येत[2] इदानींतनीमपि सर्वां भूमिं मन्येत जानीयात् । ज्ञातुं शक्नोतीत्यर्थः ॥

अष्टमी ॥

कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।
कुतस्त्वष्टा समभवत् कुतो धाताजायत ॥ ८ ॥
कुतः । इन्द्रः । कुतः । सोमः । कुतः । अग्निः । अजायत ।
कुतः । त्वष्टा । सम् । अभवत् । कुतः । धाता । अजायत ॥ ८ ॥

धात्रादयो देवा अजाता आसन्निति उक्तम् । तेषाम् उत्पत्तिकारणम् अनया पृच्छ्यते[3] । कुतः कस्मात् कारणाद् इन्द्रः अजायत उदपद्यत । एवम् उत्तरत्रापि योजना । एषां प्रश्नानां प्रतिवचनम् उत्तरया ऋचा क्रियते ॥

नवमी ॥

इन्द्रादिन्द्रः सोमात् सोमो अग्नेरग्निरजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥ ९ ॥
इन्द्रात् । इन्द्रः । सोमात् । सोमः । अग्नेः । अग्निः । अजायत ।
त्वष्टा । ह । जज्ञे । त्वष्टुः । धातुः । धाता । अजायत ॥ ९ ॥

पूर्वस्मिन् कल्पे यादृग्रूप इन्द्रस्तस्माद् इन्द्राद् इदानींतन इन्द्रो जज्ञे । तत्समानरूपो जात इत्यर्थः । एवं सोमात् सोम इत्यादिषु योजना ।

1 S' °सार्वज्ञाः. 2 S' मन्यते. 3 S' पृच्छते.

पूर्वपूर्वसृष्ट्यनुसारेणैव इदानींतना अपि इन्द्रादयो देवाः सृष्टा इत्यर्थः । "सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत्" इति श्रुतेः [ऋ॰ सं॰ १०. १९०. ३] । यद्वा इन्द्रात् इन्द्रत्वप्रापकात् कर्मणः इन्द्रो जज्ञे । इन्द्रशब्दः स्वकारणभूते कर्मणि उपचर्यते । इत्थं सोमात् सोम इत्यादावपि द्रष्टव्यम् । "तपो ह जज्ञे कर्मणस्तत् ते ज्येष्ठम् उपासते" [६] इति हि कर्मणः सर्वजगत्कारणत्वम् उक्तम् । ⌛अस्मिन् पक्षे इन्द्राद् इन्द्र इति "जनिकर्तुः प्रकृतिः" इति पञ्चमी⌛ । अथ वा अधिभूतम् अवस्थिता ये इन्द्रादयः तेभ्यः सकाशाद् अध्यात्मम् अवस्थितानाम् अधिष्ठातृदेवानाम् उत्पत्तिः कथ्यत इति बोद्धव्यम् ॥

दशमी ॥

ये त आसन् दश जाता देवा देवेभ्यः पुरा ।
पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥ १० ॥ (२२)

ये । ते । आसन् । दश । जाताः । देवाः । देवेभ्यः । पुरा ।
पुत्रेभ्यः । लोकम् । दत्त्वा । कस्मिन् । ते । लोके । आसते ॥ १० ॥ (२२)

देवेभ्यः अधिष्ठातृभ्यः अग्न्यादिदेवताभ्यः पुरा पूर्वं ये ते देवाः प्रागुक्ताः प्राणापानाद्या दशसंख्याका जाता आसन् ते पुत्रेभ्यः आत्मजेभ्यो लोकम् स्वकीयं स्थानं दत्त्वा कस्मिन् लोके स्थाने आसते उपविशन्ति । यथा लौकिका जनाः पुत्रान् उत्पाद्य तेषां स्वकीयं स्थानं दत्त्वा स्थानान्तरं स्वनिवासार्थम् आश्रयन्ति एवम् एषां सृष्टानाम् इन्द्रियाणां तदधिष्ठातॄणां च देवानां निवासाश्रयः क इति प्रश्नार्थः । अस्य प्रश्नस्य "देवाः पुरुषम् आविशन्" [१३] इति प्रतिवचनम् अग्रे भविष्यति ॥

[इति] चतुर्थेनुवाके चतुर्थं सूक्तम् ॥

पञ्चमसूक्ते प्रथमा ॥

यदा केशानस्थि स्नाव मांसं मज्जानमाभरत् ।

---

१ PJ आसन् ।. We with [2]P Cp.

शरीरं कृत्वा पादवत् कं लोकमनु प्राविशत् ॥ ११ ॥

यदा । केशान् । अस्थि । स्नाव । मांसम् । मज्जानम् । आऽअभरत् ।

शरीरम् । कृत्वा । पादऽवत् । कम् । लोकम् । अनु । प्र । अविशत् ॥११॥

यदा यस्मिन् सृष्टिकाले केशान् शिरोरुहान् अस्थिस्नावादिधातून् शरीरोपादानभूतान् स्रष्टा समभरत् एकत्र संभृतवान् । तत्र अस्थि प्रसिद्धम् स्नाव अस्थ्नां संधिबन्धनार्थं सिराजालम् मांसम् प्रसिद्धम् मज्जा अस्थ्यन्तर्गतो रसः । तैः संभृतैः पादवत् । उपलक्षणम् एतत् । हस्तपादाद्यङ्गोपाङ्गसहितं शरीरं कृत्वा निर्माय । तदानीं कम् अन्यं लोकं स्थानम् अनु प्राविशत् । तदेव शरीरम् आत्मभावेन प्राविशद् इत्यर्थः । "तत् सृष्ट्वा तदेवानुप्राविशत्" [तै॰ आ॰ ८. ६] "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" [छा॰ उ॰ ६. ३. २] इत्यादिश्रुतेः ॥

द्वितीया ॥

कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत् ।

अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥ १२ ॥

कुतः । केशान् । कुतः । स्नाव । कुतः । अस्थीनि । आ । अभरत् ।

अङ्गा । पर्वाणि । मज्जानम् । कः । मांसम् । कुतः । आ । अभरत् ॥१२॥

केशादीन् संभृत्य ईश्वरः शरीरं सृष्टवान् इत्युक्तम् । अत्र केशाद्युपादानत्वं स्रष्टृत्वं च वस्त्वन्तरविरहात् स्वात्मन एवेति काक्वा प्रतिपाद्यते । स्रष्टा ईश्वरः कुतः कस्माद् उपादानकारणात् केशान् सम् अभरत् । किं तदुपादानकारणम् । न किंचिद् अस्ति । "सदेव सोम्येदम् अग्र आसीत् एकमेवाद्वितीयम्" [छा॰ उ॰ ६. २. १] इति अद्वितीयत्वश्रुतेर्वस्त्वन्तरस्याभावात् स्वात्मन एव केशादीन् समभरद् इत्यर्थः । तथा च अभिन्ननिमित्तोपादानत्वम् ईश्वरस्य श्रूयते । "सोकामयत बहु स्यां प्रजायेयेति" [तै॰ आ॰ ८. ६] । तत्र कामयितृत्वात् कुलालादिवन्निमि-

---

१ P मासम् ।. २ KK[m] V स्नावः. We with ABB[h]CDERS[m]PP[2]JCs. ३ P[2] स्नावं ।. We with PJCp. ४ P मासम् ।. We with P[2]JCp.

त्वम् । प्रजायेयेति उत्तमपुरुषश्रुत्या स्वस्यैव बहुभावावस्थानप्रतिपादनाद् उपादानत्वम् । आह[1] च भगवान् बादरायणः । "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" [बा० १. ४. २३] इति । तथा कुतः कस्माद् उपादानकारणात् स्नाव उत्पन्नम् । न कस्माच्चित् । किं तु स्वस्मादेव । एवम् उत्तरत्रापि योज्यम् । अङ्गा अङ्गानि हस्तपादादीनि पर्वाणि तत्संधीन् मज्जानम् अस्थ्यन्तर्गतं रसम् । कर्मकर्तृभावस्य एकत्र विरोधात् केशाद्युपादानभूताद् अन्य एव कश्चित् संभर्ता स्याद् इत्याशङ्क्य तदनन्यत्वमपि प्रतिपादयति क इति । कः अन्यः एतान् आभरत् । न कश्चिद् अस्ति । उपादानभावेन स्थित एव ईश्वरः केशादीनाम् आहर्तापि अभवद् इत्यर्थः । विचित्रशक्तियोगित्वेन एकस्यैव कर्तृत्वं कर्मत्वं च न व्याहन्यत इत्यर्थः । यद्वा कुतः केशान् इत्यादिषु सर्वत्र कारणप्रश्नमात्रं क्रियते । को मांसम् इति कर्तृप्रश्नमात्रम् । तस्य सर्वस्य प्रतिवचनम् उत्तरया क्रियते ॥

तृतीया ॥

संसिचो नाम ते देवा ये संभारान्त्[1]समभरन् ।
सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥ १३ ॥

सम्ऽसिचः । नाम । ते[2] । देवाः । ये । सम्ऽभारान् । सम्ऽअभरन् ।
सर्वम् । सम्ऽसिच्य । मर्त्यम् । देवाः । पुरुषम् । आ । अविशन् ॥१३॥

ये देवाः प्रागुक्ता ज्ञानेन्द्रियकर्मेन्द्रियात्मकाः साधिष्ठातृकाः प्राणापानाद्या वा संभारान् संभ्रियन्त इति संभाराः प्राग् उदीरिताः [केशा]द्याः तान् समभरन् एकत्र संभृतवन्तः ते देवाः संसिचो नाम । संसिञ्चन्ति । सम् इति एकीभावे । तान् संभारान् एकीकृत्य बन्धकेन रसेन आबध्नन्तीति संसिचः संसेचनसमर्थाः । संधायका इत्यर्थः । ते मर्त्यम्

---

१ K $\overset{m}{K}$ संभागंत्सम°, a reading clearly due to a misreading of a letter in a MS. Cs °भारान् समभरन्. We with A B $\overset{h}{B}$ C D E R $\overset{m}{S}$ P $\overset{2}{P}$ J V. २ P ते।. We with $\overset{2}{P}$ J Cp.

1 S′ omit °ह च भगवान् बा°.

मरणधर्माणम् सर्वं शरीरं संसिच्य असृजा आर्द्रीकृत्य पुरुषम् पुरुषाकृतिं कृत्वा तम् आविशन् प्रविष्टवन्तः । यावत् शरीरे प्राणा निवसन्ति तावन्तं कालं प्राणाधिष्ठितं शरीरं सर्वव्यवहारक्षमं भवति । तस्मात् प्राणदेवाः पृथिव्यादिपञ्चभूतमात्राभ्यः समुद्भूतं प्रागुदीरितकेशास्थ्यादिधातुमयं पुरुषशरीरं प्रविश्य वर्तन्त इत्यर्थः ॥

चतुर्थी ॥

ऊरू पादा॑वष्ठीव॒न्तौ॒ शिरो॒ हस्ता॒वथो॒ मुख॑म् ।
पृष्टी[१]र्ब॑र्ज॒ह्ये॒ पा॒र्श्वे कस्तत् सम॑दधा॒दृषिः ॥ १४ ॥

ऊ॒रू इति॑ । पादौ॑ । अ॒ष्ठी॒वन्तौ॑ । शिरः॑ । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् ।
पृ॒ष्टीः[२] । ब॒र्ज॒ह्ये॒[३] इति॑ । पा॒र्श्वे[४] इति॑ । कः । तत् । सम् । अ॒द॒धा॒त् । ऋषिः[५] ॥१४॥

ऊरू जान्वोरुपरि वर्तमानौ । पादौ तयोरधस्ताद्भागौ । अष्ठीवन्तौ ऊरुपादयोर्मध्यस्थे जानुनी । शिरः मूर्धानम्[1] । हस्तौ बाहू । अथो अपि च मुखम् आस्यम् । पृष्टीः पृष्ठवंशस्य अभितो वर्तमानाः पर्शूः[2] । बर्जह्ये एतत्संज्ञौ अवयवौ । उभे पार्श्वे । तत् अनुक्रान्तं सर्वम् अङ्गजातं क ऋषिः संधानोपायज्ञानवान् समदधात् परस्परं संहितं संश्लिष्टं कृतवान् । अस्य प्रश्नस्य प्रतिवचनम् उत्तरया क्रियते ॥

पञ्चमी ॥

शिरो॒ हस्ता॒वथो॒ मुखं॒ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः[६] ।
त्व॒चा प्रावृ॑त्य॒ सर्वं॒ तत् सं॒धा सम॑दधा॒[७]न्म॒ही ॥ १५ ॥

शिरः॑ । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । जि॒ह्वाम् । ग्री॒वाः । च॒ । कीक॑साः ।

१ K K^m C E S^m पृष्टी°. We with A B B^h D R V Cs Dc. २ P P^2 J Cp पृष्टीः।. ३ J बर्जह्ये इति।. P P^2 बर्जह्ये इति।. We with Cp. ४ P पार्श्वेन्। इति। corrected to पार्श्वे इति. We with P^2 J. ५ P omits the visarga. We with P^2 J. ६ B^h K V omit the visarga. Cs is doubtful. In it an old anusvâra may have been cancelled or a new one may have been inserted. We with A B C D E K^m R S^m P P^2 J V. ७ B संमदधा°.

1 S′ मूर्धा. 2 S′ पर्शुः.

त्वचा । प्रऽआवृत्यं । सर्वम् । तत् । सम्ऽधा । सम् । अदधात् । मही ॥१५॥

शिरः मूर्धानम् । हस्तौ बाहू । अथो अपि च मुखम् आस्यम् । जिह्वाम् तन्मध्ये वर्तमानां रसनाम् । ग्रीवाः कन्धराः । कीकसाः कीकसान् अस्थीनि । उपलक्षणम् एतत् । एतदुपलक्षितानि प्रागुदीरितानि अस्थिस्नावादीनि ऊरुपादादीनि च सर्वाणि अङ्गानि त्वचा चर्मणा प्रावृत्य प्रावृतानि आच्छन्नानि कृत्वा सर्वं तत् अङ्गजातं मही । ⌛वर्णोपजनश्छान्दसः⌛ । महती संधा संधानकर्त्री देवता समदधात् संहितं परस्परसंश्लिष्टं स्वस्वव्यापारक्षमं कृतवती । ⌛संधेति । "आतश्चोपसर्गे" इति संपूर्वाद् दधातेः कर्तरि कप्रत्ययः⌛ ॥

षष्ठी ॥

यत्तच्छरीरमशयत् संधया संहितं महत् ।
येनेदमद्य[1] रोचते को अस्मिन् वर्णमाभरत् ॥ १६ ॥

यत् । तत् । शरीरम् । अशयत् । सम्ऽधया । सम्ऽहितम् । महत् ।
येन । इदम् । अद्य । रोचते । कः । अस्मिन् । वर्णम् । आ[2] । अभरत् ॥१६॥

तत् उक्तप्रकारं यत् शरीरं संधया संधात्र्या देवतया संहितं कृतावयवसंधानं महत् प्रवृद्धम् अशयत् शेते । वर्तत इत्यर्थः । इदं शरीरम् अद्य इदानीं येन वर्णेन कृष्णगौरादिरूपेण रोचते दीप्यते अस्मिन् शरीरे को नाम देवः तं वर्णम् आभरत् आहरत् संपादितवान् । अस्य प्रतिवचनम् उत्तरया क्रियते ॥

सप्तमी ॥

सर्वे देवा उपाशिक्षन् तदजानाद् वधूः सती[3] ।
ईशा वशस्य[4] या जाया सास्मिन् वर्णमाभरत् ॥ १७ ॥

---

१ K V तेनेद॰. We with A B $\overset{h}{B}$ C D E R $\overset{m}{S}$ P $\overset{2}{P}$ J Cs. २ P $\overset{2}{P}$ J Cp आऽअभरत् ।. The correction is mine. ३ A $\overset{h}{B}$ सतीः. We with B C D E $\overset{m}{K}$ K R $\overset{m}{S}$ V. ४ K V विश्वंस्य. We read वशंस्य with A C D E $\overset{m}{K}$ R $\overset{m}{S}$ P $\overset{2}{P}$ J V Cs.

सर्वे॑ । दे॒वाः । उप॑ । अ॒शि॒क्ष॒न् । तत् । अ॒जा॒ना॒त् । व॒धूः । स॒ती ।
ई॒शा । व॒श॑स्य । या । जा॒या । सा । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥ १७ ॥

सर्वे इन्द्रादयो देवाः उपाशिक्षन् समीपे शक्ता भवितुम् ऐच्छन् । वधूः सती परमेश्वरेण कृतोद्वाहा भगवती[1] आद्या परचिद्रूपिणी शक्तिः तत् देवैः कृतम् अजानात् ज्ञातवती । या एषा विश्वस्य[*] सर्वस्य जगतः ईशा ईशाना नियन्त्री मायाशक्तिः । "यन्मन्युर्जायाम् आवहद्" [१] इति ह्युक्तम् । सा पारमेश्वरी[2] शक्तिः अस्मिन् षाट्कौशिके[3] शरीरे गौरपीतनीलादिवर्णम् आभरत् आहरत् । उदपादयद् इत्यर्थः ॥

अष्टमी ॥

य॒दा त्वष्टा॒ व्यतृ॑णत् पि॒ता त्वष्टु॒र्य उत्त॑रः ।
गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥ १८ ॥

य॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टुः॑ । यः । उत्त॑रः ।
गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वाः । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥ १८ ॥

यत् पूर्वं सामान्येन उक्तं "देवाः पुरुषमाविशन्" इति तद् अत्र विशेष्यते । "यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते" इति हि श्रूयते [तै॰ सं॰ १. ५. ९. २] । तत्र यः अध्यात्मम् अवस्थितस्त्वष्टा मनुष्यगवाश्वादिरूपाणां विकर्ता देवः तस्य त्वष्टुः पिता उत्पादकः उत्तरः उत्कृष्टतरो यस्त्वष्टा अधिदैवं[4] स्थितः विचित्रस्य जगतो निर्माता एतत्संज्ञो देवः स यदा यस्मिन् काले व्यतृणत् विविधं चक्षुःश्रोत्रादीनि छिद्राणि पुरुषशरीरे तर्दनेन अकरोत् । ⌛ उतृदिर् हिंसानादरयोः ⌛ । तदा मर्त्यम् मरणधर्मकं त्वष्ट्रा देवेन वितृण्णं बहुच्छिद्रं पुरुषशरीरं गृहं कृत्वा आवासस्थानं कृत्वा देवाः [इन्द्रियाणि] प्राणापानादयश्च तं पुरुषम् आविशन् प्रविष्टवन्तः ॥

---

१ K विश्वस्य । P व॒श॒स्यं । We with P[2] J Cp. २ B[h] मर्त्यं. ३ P गृ॒हान् । We with P[2] J Cp. ४ P[2] वि॒श॒न् ।

---

1 S' भवती. 2 S' परमेश्वरी. 3 S' षट्कौशिके. 4 S' अधिदैव°.

नवमी ॥

स्वप्नो वै तन्द्रीर्निर्ऋतिः पाप्मानो नाम देवताः ।
जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥ १९ ॥
स्वप्नः । वै । तन्द्रीः । निःऽऋतिः । पाप्मानः । नाम । देवताः ।
जरा । खालत्यम् । पालित्यम् । शरीरम् । अनु । प्र । अविशन् ॥१९॥

इत्थं शरीरस्योत्पत्तिम् अभिधाय प्रथमसृष्टानाम् इन्द्रियाणां प्राणापानादीनां च तत्र प्रवेश उक्तः । तावता सात्मकं सत् तच्छरीरं सर्वव्यवहारक्षमं जातम् । इतः परं सर्वविकाराश्रयत्वम् अस्य उच्यते । स्वप्नः स्वापो निद्रा । ञिष्वप् शये । "स्वपो नन्" इति भावे नन् प्रत्ययः । वैशब्दो लोकप्रसिद्धिं[1] द्योतयति । तन्द्री अलसता । निर्ऋतिः पापदेवता दुर्गतिः । पाप्मानः ब्रह्महत्यादिपापानि । स्वप्नादिरूपा एता देवताः पुरुषशरीरम् अनु प्राविशन् । तथा जरा वयोहानिकरी चरमावस्था । खालित्यम् चित्तस्य चक्षुरादीनां च स्खलनम् । पालित्यम् पलितत्वम् । एतदभिमानिनो देवाश्च शरीरम् अनु प्राविशन् ॥

दशमी ॥

स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत् ।
बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥ २० ॥ (२३)
स्तेयम् । दुःऽकृतम् । वृजिनम् । सत्यम् । यज्ञः । यशः । बृहत् ।
बलम् । च । क्षत्रम् । ओजः । च । शरीरम् । अनु । प्र । अविशन् ॥ २० ॥

स्तेयम् स्तैन्यं तस्करत्वम् । "स्तेनाद् यन्नलोपश्च" इति स्तेनशब्दाद् भावे यत् प्रत्ययो नलोपश्च । दुष्कृतम् दुष्कर्म सुरापानादिकम् । वृजिनम् तज्जनितं दुरितम् । सत्यम् यथार्थकथनम् । यज्ञो यागः । यशः कीर्तिः । बृहत् प्रभूतम् । यशसो विशेषणम् एतत् । बलम् प्रसिद्धम् एतत् । क्षत्रम् क्षत्रियसंबन्धि तेजः । ओजः शरीरगतो

१ R B[h] प्राविशत्. We with A B C D E K K[m] S[m] V Cs.

1 S' °प्रसिद्धं.

बलहेतुरष्टमो धातुः । [एते] सर्वे पुरुषस्य शरीरम् अनु प्राविशन् । जीवच्छरीरम् आश्रित्य उत्पद्यन्त इत्यर्थः ॥

[इति] चतुर्थेनुवाके पञ्चमं सूक्तम् ॥

षष्ठसूक्ते प्रथमा ॥

भूतिश्च वा अभूतिश्च रातयोरातयश्च याः ।
क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥ २१ ॥

भूतिः । च । वै । अभूतिः । च । रातयः । अरातयः । च । याः ।
क्षुधः । च । सर्वाः । तृष्णाः । च । शरीरम् । अनु । प्र । अविशन् ॥ २१ ॥

भूतिः समृद्धिः । अभूतिः असमृद्धिः । ♁परस्परसमुच्चयार्थौ चकारौ♁ । वैशब्दः प्रसिद्धौ । रातयो मित्राणि । अरातयः शत्रवः । या इमा भूतिप्रभृतयः क्षुधः बुभुक्षा अन्नाकाङ्क्षाः तृष्णाः पिपासाः एताश्च सर्वाः पुरुषस्य शरीरम् अनु प्राविशन् । आश्रित्य प्रभवन्तीत्यर्थः ॥

द्वितीया ॥

निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥ २२ ॥

निन्दाः । च । वै । अनिन्दाः । च । यत् । च । हन्त । इति । न । इति । च ।
शरीरम् । श्रद्धा । दक्षिणा । अश्रद्धा । च । अनु । प्र । अविशन् ॥ २२ ॥

निन्दाः कुत्सनानि । अनिन्दाः अकुत्सनानि । हन्तेति हर्षे । यच्च वस्तु हर्षजनकम् । नेत्ययं शब्दः संनिहितस्य हन्तार्थस्य हर्षस्य निषेधे । यच्च वस्तु हर्षाजनकम् । श्रद्धा श्रद्धानम् अभिलाषविशेषः । दक्षिणा दक्ष्यते समृध्यते अनयेति दक्षिणा धनसमृद्धिः । ♁दक्ष वृद्धौ इत्यस्माद् द्रुदक्षिभ्याम् इनन् [उ° २. ५०] इति इनन् प्रत्ययः♁ । अ-

१ B दक्षिणाश्रद्धा. A B[h] C D R S[m] K Cs दक्षिणाश्रद्धा. E दक्षिणाः श्रद्धा. Dc दक्षिणाश्रद्धा° corrected to दक्षिणाश्रद्धा°. We with K[m] V Dc. २ P[2] हतं ।. J हंतं ।. P हंताः । changed to हंता ।. We with J Cp. ३ P J दक्षिणा ।. We with P[2] Cp.

श्रद्धा अश्रद्धानाभावः अभिलाषराहित्यम् एतानि[1] सर्वाणि[1] पुरुषस्य शरीरम् अनु प्राविशन् । तद् आश्रित्य प्रादुर्भवन्तीत्यर्थः ॥

तृतीया ॥

विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥ २३ ॥

विद्याः । च । वै । अविद्याः । च । यत् । च । अन्यत् । उपऽदेश्यम् ।
शरीरम् । ब्रह्म । प्र । अविशत् । ऋचः । साम । अथो इति । यजुः ॥ २३ ॥

विद्याः शास्त्रजनितज्ञानानि । अविद्याः अज्ञानानि । यच्चान्यत् वस्तु उपदेश्यम् उपदेश[2]समधिगम्यं विद्याविद्यानाम् आश्रयभूतं तच्छाब्दं ब्रह्म पुरुषस्य शरीरं प्राविशत् । परापश्यन्त्यादिरूपेण तत्रैव प्रादुर्भवतीत्यर्थः ॥ अथो अपि च ऋक्सामयजुरात्मकास्त्रयो वेदाः पुरुषशरीरम् अनु प्राविशन् । यद्वा ऋगादीनां पृथगुपादानात् तदङ्गभूताः पुराणादयो विद्याशब्देन विवक्षिताः । अविद्याशब्देन च वेदविरुद्धागमाः ॥

चतुर्थी ॥

आनन्दा मोदाः प्रमुदो[१]ऽभीमोदमुदश्च ये ।
हसो न[२]रिष्टा नृत्तानि शरीरमनु प्राविशन् ॥ २४ ॥

आऽनन्दाः । मोदाः । प्रऽमुदः । अभिमोदऽमुदः । च । ये ।
हसः । नरिष्टा । नृत्तानि । शरीरम् । अनु । प्र । अविशन् ॥ २४ ॥

पूर्वोर्धर्चौ व्याख्यातः [११.९.२६] । हसः हासः । ⌛ हसे हसने । "स्वनहसोर्वा" इति भावे अप् ⌛ । नुरिष्टाः* मनुष्यस्य इ-

१ B प्रमोदौ°. We with A B C D E R S K K V Cs. २ K नुरिष्टां. J नरिष्टां. We with A B B C D E K R S P P V Cs Cp Dc. Here Sâyaṇa might not have had the padapâṭha before him. Whatever नरिष्टा may mean (*vide* VII. 12. 2; also VS. 30. 6), नुः इष्टा can hardly be the text, as taken by Sâyaṇa, who seems here inferior to the unanimous testimony of the MSS.

1 S′ एतत्सर्वम् for एतानि सर्वाणि. 2 S′ उपदेश्य°.

च्छागोचराः शब्दस्पर्शादिविषयाः । नृत्तानि नर्तनानि भरतशास्त्रोक्तानि । एते आनन्दादयः सर्वे पुरुषस्य शरीरम् अनु प्राविशन् ॥

पञ्चमी ॥

आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः ॥ २५ ॥

आऽलापाः । च । प्रऽलापाः । च । अभिलापऽलपः । च । ये ।
शरीरम् । सर्वे । प्र । अविशन्[1] । आऽयुजः । प्रऽयुजः । युजः ॥ २५ ॥

आलापाः आभाषणानि सार्थकानि वचनानि । प्रलापाः निरर्थकानि वचनानि[1] । लप व्यक्तायां वाचि । भावे घञ् । ये च अभीलापलपः अभिलापः उक्तविधः शब्दः तेन लपन्ति[2] ब्रुवन्तीति अभीलापलपः शब्दस्य उच्चारयितारः । "क्विप् च" इति लपेः क्विप् । ते सर्वे आलापादयः पुरुषशरीरं प्राविशन् । आयुजः आयोजनानि प्रयुजः प्रयोजनानि युजः योजनानि । सर्वत्र संपदादिलक्षणो भावे क्विप् । उपसर्गवशाद् अमीषाम् अर्थभेदोऽवगन्तव्यः । एवम् आयोजनादिक्रियाः शरीरम् अनु प्राविशन् ॥

षष्ठी ॥

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥ २६ ॥

प्राणापानौ । चक्षुः । श्रोत्रम् । अक्षितिः । च । क्षितिः । च । या ।
व्यानऽउदानौ । वाक् । मनः । शरीरेण । ते । ईयन्ते ॥ २६ ॥

त्रयः पादाः पूर्ववद् [११.९.२५] व्याख्येयाः । ते प्राणापानादयः सर्वे शरीरम् अनुप्रविश्य तेन सह ईयन्ते स्वस्व[3]व्यापारेषु प्रवर्तन्ते । ईङ् गतौ । दिवादित्वात् श्यन् प्रत्ययः ॥

---

१ P² अविशत् ।. We with P J Cp.

---

1 S′ ——नि for वचनानि. 2 S′ लपं——वंतीति. 3 S′ स्वस्य for स्वस्व°.

सप्तमी ॥

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।
चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥ २७ ॥

आऽशिषः । च । प्रऽशिषः । च । सम्ऽशिषः । विऽशिषः । च । याः ।
चित्तानि । सर्वे । सम्ऽकल्पाः । शरीरम् । अनु । प्र । अविशन् ॥ २७ ॥

आशिषः आशासनानि इष्टफलप्रार्थनानि । "आशासः क्वौ॰" इति वचनाद् इत्वम् । तथा प्रशिषः प्रशासनानि । संशिषः संशासनानि । विशिषः विविधानि शासनानि । अत्र उपसर्गवशाद् धात्वर्थस्य भेदोऽवगन्तव्यः । या एता आशीराद्याः सन्ति । चित्तानीति बहुवचनेन मनोबुद्ध्यहंकाराः संगृह्यन्ते । तथा संकल्पा इति बहुवचनेन सर्वा अन्तःकरणवृत्तयः । एते सर्वे पुरुषस्य शरीरम् अनु प्राविशन् ॥

अष्टमी ॥

आस्नेयीश्च वास्नेयीश्च त्वरणाः कृपणाश्च याः ।
गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥ २८ ॥

आस्नेयीः । च । वास्नेयीः । च । त्वरणाः । कृपणाः । च । याः ।
गुह्याः । शुक्राः । स्थूलाः । अपः । ताः । बीभत्सौ । असादयन् ॥ २८ ॥

आसमन्तात् स्नानम् आस्नेयम् । ष्णा शौचे । "अचो यत्" इति भावे यत् । "ईद्यति" इति ईत्वम् । तत्संबन्धिन्य आपः आस्नेय्यः । "तस्येदम्" इति अण् । "टिड्ढाणञ्॰" [इति ङीप्] । वाशब्दो विकल्पार्थः । तस्य सुप् सुपेति स्नेयशब्दे-

१ B[h] K[m] P[2] Cs आस्तेयीश्च. Dc आस्नेयी॰ corrected to आस्तेयी॰. A B C D E R S[m] K P J V आस्नेयीश्च. २ A B B[h] C D E K[m] R S[m] P P[2] J Cp Dc: वास्तेयीश्च. K V वास्नेयीश्च with Sâyaṇa. ३ B B[h] C E R शुक्राः. We with A D S[m] V Cs. ४ P त्वरणः।. We with P[2] J Cp. ५ P[2] अपः।. We with P J Cp.

न समासः⧗ । विकल्पेन स्नानं वास्नेयं[*] तत्संबन्धिन्य[1] आपः[1] । यद्वा । ⧗आस उपवेशने इत्यस्माद् औणादिको नप्रत्ययः⧗ । आसनस्य शरीरे प्राणावस्थानस्य निमित्तभूता आपः आस्नेय्यः । तथा वस्नम् मूल्यद्रव्यं सर्वव्यवहारास्पदं शरीरं तदुपादानभूता आपः वास्नेय्यः[*] । "पञ्चम्याम् आहुतावापः पुरुषवचसो भवन्ति" इति श्रुतेः । ⧗आस्नशब्दाद् वस्नशब्दाच्च शैषिको ढक् प्रत्ययः⧗ । तथा त्वरणाः त्वरया गच्छन्त्यः । कृपणाः कृशा अल्पाः । एवंभूताश्च या आपः सन्ति । [याश्च] गुह्याः गुहायां भवाः । शुक्राः शुक्लवर्णाः शुक्रात्मना[2] परिणता वा । स्थूलाः स्थौल्योपेता महत्यः आपः[*][3] व्यापनशीला नद्यादिरूपेण वर्तमानाः [ताः] सर्वा आपः बीभत्सौ बीभत्स्यमाने जुगुप्स्यमाने पुरुषशरीरे असादयन् । अथ वा ता एव आपो बीभत्सौ जुगुप्स्यमाने[4] पुरुषे स्वकार्यं शरीरम् असादयन्नित्यर्थः । ⧗बध बन्धने । "मान्बधदान्शान्भ्यः०" इति सन् प्रत्ययः । स च "बधेर्वैरूप्ये" इति स्मरणात् कुत्सनेऽर्थे भवति । "सनाशंसभिक्ष उः" इति उप्रत्ययः⧗ ॥

नवमी ॥

अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन् ।
रेतः॑ कृ॒त्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥ २९ ॥

अस्थि॑ । कृ॒त्वा । स॒म्ऽइध॑म् । तत् । अ॒ष्ट । आपः॑ । अ॒सा॒द॒य॒न् ।
रेतः॑ । कृ॒त्वा । आ॒ज्य॑म्[१] । दे॒वाः । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥ २९ ॥

अस्थि प्राणिशरीरसंबन्धि अस्थिजातं समिधम् समिन्धनसाधनं शरीरपरिपाकस्य निमित्तं कृत्वा तत् तत्र षाट्कौशिके शरीरे अष्टसंख्याका आस्नेयीश्चेत्यादिना अनुक्रान्ता अपः[*] असादयन् । तस्य समिन्धनस्य अभिवृद्धिकारणम् आज्यं रेतः शुक्लं[5] कृत्वा परिकल्प्य । अत्रास्थीनि पुरुषश-

---

१ P अज्यम् ।. We with P[2] J Cp.

1 S′ तत्संबधिनीरपः. 2 S′ शुक्लात्मना. 3 So the text too in S′. 4 S′ जुगुप्स° for जुगुप्स्य°. 5 So S′.

रीरान्तर्गतानि शरीरवृद्धिहेतुत्वात् समित्त्वेन रूप्यन्ते रेतश्च स्वशरीरवृद्धेः पुत्राद्युत्पत्तिहेतुत्वेन च आज्यत्वेन रूप्यते । अत एव तैत्तिरीयके अग्न्याधेयप्रकरणे आधीयमानासु समित्सु अस्थित्वं तदञ्जनसाधने आज्ये रेतस्त्वं च आरोप्य स्तूयते । "अस्थि वा एतद् यत् समिधः । एतद् रेतो यद् आज्यम्" इति [तै॰ब्रा॰ १.१.९.४] । इत्थं कृत्वा देवाः इन्द्रियाणि तदधिष्ठातारः अग्न्यादयो वा पुरुषशरीरं प्राविशन् ॥

दशमी ॥

या आपो याश्च देवता या विराड् ब्रह्मणा सह ।
शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥ ३० ॥

याः । आपः । याः । च । देवताः । या[1] । विऽराट् । ब्रह्मणा । सह ।
शरीरम् । ब्रह्म । प्र । अविशत् । शरीरे । अधि । प्रजाऽपतिः ॥ ३० ॥

याः प्रागुदीरिता आपः याश्च देवताः इन्द्रियाभिमानिन्यः या श्च "विराड् वा इदम् अग्र आसीत्" [८.१०.१] इत्यादिना सार्वात्म्येन उक्ता विराट्संज्ञा देवता ब्रह्मणा ब्राह्मणतेजसा सह वर्तमाना ताः सर्वाः शरीरं प्राविशन्[2] । तदनन्तरं यज्जगत्कारणं परं ब्रह्म तदपि अन्तर्यामिरूपेण तच्छरीरं प्राविशत् । तस्मिन् शरीरे [अधि] प्रजापतिः प्रजानां पालयिता पुत्राद्युत्पादको जीवो वर्तते ॥

एकादशी ॥

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये ॥ ३१ ॥

सूर्यः । चक्षुः । वातः । प्राणम् । पुरुषस्य । वि । भेजिरे ।
अथ । अस्य । इतरम् । आत्मानम् । देवाः । प्र । अयच्छन् । अग्नये ॥ ३१ ॥

"आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्" [ऐ॰ आ॰ २.४.२] इति श्रुतेः

१ Cp याः. We with PP²J. २ KK^m अथो॰. We with ABB^hCDERS^mV Cs.

1 S′ याश्च for या च. 2 S′ प्राविशत्.

सूर्यः चक्षुरभिमानी देवः । स च पुरुषस्य संबन्धि चक्षुरिन्द्रियम् आत्मीयभागत्वेन स्वीकृतवान् । वातः वायुः प्राणम् घ्राणेन्द्रियं भागत्वेन स्वीचकार । "वायुः प्राणो भूत्वा नासिके प्राविशत्" [ऐ॰आ॰२.४.२] इति श्रुतेः । उपलक्षणम् एतत् । एवम् अन्यान्यपि इन्द्रियाणि पुरुषसंबन्धीनि तत्तदधिदेवता वि भेजिरे विभज्य स्वीकृतवत्यः । अथ अनन्तरम् इतरम् प्राणेन्द्रियव्यतिरिक्तम् आत्मानम् षाट्कौशिकं स्थूलशरीरम् अग्नये सर्वे देवा भागत्वेन प्रायच्छन् । अग्निना मरणानन्तरं स्थूलशरीरमेव केवलं दह्यते ।

ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि ।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ।

इति यत् सप्तदशात्मकं[1] लिङ्गशरीरम् उक्तं तस्य मुक्तिपर्यन्तं विनाशाभावात् तत्तद्देवतारूपेण अवस्थानमेवेत्यर्थः ॥

द्वादशी ॥

तस्माद् वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥ ३२ ॥

तस्मात् । वै । विद्वान् । पुरुषम् । इदम् । ब्रह्म । इति । मन्यते ।
सर्वाः । हि । अस्मिन् । देवताः । गावः । गोस्थेऽइव । आसते ॥ ३२ ॥

तस्मात् खलु कारणात् विद्वान् उक्तप्रकारं सर्वं जानन् पुरुषम् पुरुषशरीरम् इदम् अपरोक्षम् अन्तर्बहिर्व्याप्य अवस्थितं ब्रह्मेति मन्यते जानाति । कुत इत्यत आह । हि यस्मात् सर्वा देवताः प्राणापानादिवायवः सर्वेन्द्रियाणि तदधिष्ठातारः अग्न्यादयश्च अस्मिन् शरीरे आसते निवसन्ति । तत्र दृष्टान्तः गावो गोष्ठ इव । यथा गावः स्वकीये गोष्ठे स्थाने विस्रम्भेण निवसन्ति तथेत्यर्थः । तस्मात् सर्वाभिर्देवताभिः आश्रितं

१ So we read with A B $\overset{h}{B}$ C D E K $\overset{m}{K}$ R $\overset{m}{S}$ P $\overset{2}{P}$ J Dc V Cs. २ Cp आसते । J आसते । corrected to आसते । We with P $\overset{2}{P}$.

1 S′ सप्तदशकात्मकं.

जीवरूपेण अन्तर्यामिरूपेण च ब्रह्मणा प्रविष्टं पुरुषशरीरं तत्तादात्म्येन विद्वान् साक्षात्करोतीत्यर्थः ॥

त्रयोदशी ॥

प्रथमेन प्रमारेण त्रेधा विष्वङ् वि गच्छति ।
अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते ॥ ३३ ॥

प्रथमेन । प्रऽमारेण । त्रेधा । विष्वङ् । वि । गच्छति ।
अदः । एकेन । गच्छति । अदः । एकेन । गच्छति । इह । एकेन । नि । सेवते ॥ ३३ ॥

शरीरम् अभिमन्यमानो जीवात्मा तेन शरीरेण तत्र प्रविष्टैरिन्द्रियैश्च पुण्यापुण्यात्मकानि कर्माणि अनुष्ठाय तत्फलोपभोगार्थं मरणानन्तरं स्वर्गनरकादीनि स्थानानि प्राप्नोति । तद् अत्र निरूप्यते । प्रथमेन प्रथमभाविना स्थूलशरीरेण प्रमारेण प्रमृतेन । हेतौ तृतीया । भोगायतनस्य शरीरस्य तदारम्भककर्मक्षयेण । त्यागाद्धेतोरित्यर्थः । त्यक्तशरीरः स जीवात्मा त्रेधा त्रिप्रकारं विष्वङ् नाना नि गच्छति नियमेन प्रयाति ॥ अदः विप्रकृष्टं स्वर्गाख्यं स्थानम् एकेन पुण्येन कर्मणा गच्छति प्राप्नोति । अदः विप्रकृष्टं नरकाख्यं स्थानम् एकेन पापेन कर्मणा गच्छति प्राप्नोति । तथा इह अस्मिन् भूलोके एकेन पुण्यपापात्मकेन मिश्रितेन कर्मणा नि षेवते नितरां सुखदुःखात्मकान् भोगान् सेवते । श्रूयते हि । "पुण्येन पुण्यलोकं नयति पापेन पापम् उभाभ्यामेव मनुष्यलोकम्" इति ॥

चतुर्दशी ॥

अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।

१ V with Sâyaṇa, विष्वङ्ङि for विष्वङ् वि. २ B^h alters to यंछति. We with K K^m B A C D E R S^m Cs. ३ B^h V गछति. We with A B C D E K K^m R S^m Cs. ४ So P P^2 J Cp.

1 S′ तदातारंभक°. 2 S′ in its text has: विष्वङ्ङिषेवते, and in its commentary: विष्वङ्नाना. Sâyaṇa apparently means to read विष्वक् and not विष्वङ्.

तस्मिंछवोध्यन्तरा तस्माच्छवोध्युच्यते ॥ ३४ ॥ (२४)

अप्ऽसु । स्तीमासु । वृद्धासु । शरीरम् । अन्तरा । हितम् ।

तस्मिन् । शवः । अधि । अन्तरा । तस्मात् । शवः । अधि । उच्यते ॥ ३४॥

स्तीमासु अनार्द्रं सर्वं जगद् आर्द्रं कुर्वतीषु । ष्टिम ष्टिम ष्टीम आर्द्रीभावे । तत्र स्तीमतेः पचाद्यच् । तथाविधासु वृद्धासु प्रवृद्धासु अप्सु उदकेषु अन्तरा मध्ये शरीरम् ब्रह्माण्डात्मकं समष्टिभूतं हितम् निहितं वर्तते । स्मर्यते हि ।

अप एव ससर्जादौ तासु वीर्यम् अवाकिरत् ।

तद् अण्डम् अभवद्धैमं कोटिसूर्यसमप्रभम् । [म॰ स्मृ॰ १. ९]

इति । तस्मिन् ब्रह्माण्डशरीरे अधि उपरि अन्तरा मध्ये च शवः बलात्मकः सूत्रात्मा सर्वाधारभूतवस्त्वात्मकः[1] परमेश्वरो वर्तते । तस्मात् समष्टिशरीराद् अधिकत्वेन स [शवः] बलात्मकः सूत्रात्मा उच्यते । श्रूयते हि । "वायुर्वै गौतम तत् सूत्रम् । वायुना वै गौतम सूत्रेणायं लोकः परश्च "लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति" इति [बृ॰ आ॰ ३. ७. ६] ॥

चतुर्थेनुवाके षष्ठं सूक्तम् ॥

[इति] एकादशकाण्डे चतुर्थोनुवाकः ॥

पञ्चमेनुवाके षट् सूक्तानि । तत्र "ये बाहवः" इत्यादि सूक्तत्रयम् अर्थसूक्तम् । "उत्तिष्ठत सं नह्यध्वम्" इत्यादि सूक्तत्रयम् अर्थसूक्तम् । आभ्याम् अर्थसूक्ताभ्यां जयकामो राजा युद्धकाले यथालिङ्गं स्वीयान् भटान् प्रति संप्रैषं कुर्यात् जपं कुर्याच्च ॥

तथा शत्रुजयकर्मणि "ये बाहवः" इत्यनुवाकेन पृषदाज्यं सक्तूंश्च जुहुयात् ॥

तथा अनेनानुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येन अक्ता धनुःसमिध आदध्यात् । इष्विध्मेग्नौ पृषदाज्येन अक्ता इषुसमिध आदध्यात् ॥

तथा अनेनानुवाकेन पृषदाज्येन धनुः संपात्य विमृज्य अभिमन्त्र्य योद्ध्रे जयकामाय राज्ञे प्रयच्छेत् ॥

1 S' °भूतवास्वात्मकः.

भाङ्गपाशान्[1] अनेनानुवाकेन पृषदाज्येन संपात्य अभिमन्त्र्य परसेनाक्रमणस्थानेषु प्रक्षिपेत् ॥

तथा मौञ्जपाशान् आमपात्राणि त्रिसंधीनि लोहमयानि पात्राणि वज्ररूपाणि अर्बुदरूपाणि वा अनेनानुवाकेन पृषदाज्येन संपात्य अभिमन्त्र्य युद्धस्थानेषु प्रक्षिपेत् ॥

तथा [अनेन] अनुवाकेन शितिपदीं गां पृषदाज्येन संपात्य अभिमन्त्र्य राज्ञश्चिह्नितकेतुदण्डे रहस्यं बध्नीयात्। अन्यां शितिपदीं गां संपात्य अभिमन्त्र्य शत्रुसेनामध्ये निरस्येत्। ततो युद्धार्थं सेनानायकम्[2] उत्सृजेत् ॥

एतत् सर्वं कौशिकेन सूत्रितम्। "ये बाहव उत्तिष्ठतेति यथालिङ्गं संप्रेष्यति। होमार्थे पृषदाज्यम्। प्रदानान्तानि वाप्यानि। वाप्यैस्त्रिषन्धी[3]नि वज्ररूपाण्यर्बुदरूपाणि। शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियायो[4]पासङ्गदण्डे[5] बध्नाति। द्वितीयाम् अस्यति" इति [कौ° २.७] ॥

तत्र प्रथमा ॥

ये बाहवो या इषवो धन्वनां वीर्याणि च।
असीन्[1] परशूनायुधं चित्ताकूतं च यद्धृदि।
सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरू[2]दारांश्च प्र दर्शय ॥ १ ॥

ये। बाहवः। याः। इषवः। धन्वनाम्[3]। वीर्याणि। च।
असीन्[4]। परशून्। आयुधम्। चित्तऽआकूतम्। च। यत्। हृदि।
सर्वम्। तत्। अर्बुदे। त्वम्। अमित्रेभ्यः। दृशे। कुरु। उत्ऽआरान्।
च। प्र। दर्शय ॥ १ ॥

ये अस्मदीयानां योद्धॄणां भटानां बाहवः आयुधग्राहिणो हस्ताः या

---

१ S^m आसीत्पं°, E असीत्पं°. K^m K V आसीन्पं°, a reading due to the text in S′ which has आसी° for असी°. We with A B^h C D R P^2 J Cs. २ B कुरु°. ३ P धन्वानाम्। ४ P आसीन्। We with P^2 J Cp.

1 S′ भाग°. 2 S′ सेनायकम्. 3 S′ °संधीनि. 4 S′ क्षत्रियायोपाशुमंकदंडे. We with *Kaus'ika.*

इषवः बाणाः तथा धन्वनाम् धनुषाम् अस्मदीयानां यानि च वीर्याणि वीरकर्माणि शत्रुनिपातनसामर्थ्यानि सन्ति तान् सर्वान् बाह्लादीन् असीन् खड्गान् परशून् परश्वधान् कुठारविशेषान् यद् अन्यदपि आयुधम् आयोधनसाधनशस्त्रम् यच्च अस्मदीयानां योद्धृणां हृदि हृदये अवस्थितं चित्ताकूतम् चित्तेन मनसा संकल्प्यमानं शत्रूणां मारणम् । यद्वा चित्तानि अस्मदीयानां भटानां धैर्ययुक्तानि मनांसि आकूतानि संकल्पाः इमम् अनेन प्रकारेण हनिष्यामि इमम् अनेनेत्येवं बहुधा भिन्नाः । ॥ "इन्द्वश्च प्राणितूर्यसेनाङ्गानाम्" इति एकवद्भावाद् एकवचनम् ॥ । ये बाहव इत्यादिना यद् एतद् अनुक्रान्तं तत् सर्वम् हे अर्बुदे । अर्बुदो नाम सर्पऋषिः । तथा च ऐतरेयके समाम्नायते । "अर्बुदः काद्रवेयः सर्पऋषिर्मन्त्रकृत्" इति [ऐ० ब्रा० ६.१] । तस्य द्वौ पुत्रौ अर्बुदिश्च[1] न्यर्बुदिश्चेति । ॥ अपत्येर्थे "अत इञ्" इति इञ् । "संज्ञापूर्वको विधिरनित्यः" इति आदिवृद्धिर्न क्रियते ॥ । अर्बुदस्य हे पुत्र हे सर्प [त्वम्] उक्तं सर्वम् अमित्रेभ्यः अस्मच्छत्रुभ्यः दृशे दृष्टये कुरु । यथा शत्रूणां मनसि भीतिर्जायते तथा अस्मदीयानि युद्धोपकरणानि दर्शयेत्यर्थः । अपि च उदारान् उन्नतान् अन्तरिक्षचरान् रक्षःपिशाचादीन् मन्त्रसामर्थ्योद्भावितान् शत्रूणां भीत्यर्थं प्रदर्शय । यद्वा सूर्यरश्मिप्रभवा उल्कादय आन्तरिक्ष्या उत्पाता उदाराः । तानपि तेभ्यः पराजयार्थं प्रदर्शय । "तस्मात् तेपानाद् उदारा अजायन्त" इति तैत्तिरीयकम् [तै० ब्रा० २.२.९.२] । उदारयन्ति आर्तिम् उद्भावयन्तीति उदाराः । ॥ ऋ गतौ । अस्मात् उत्पूर्वात् ण्यन्तात् पचाद्यच् ॥ ॥

द्वितीया ॥

उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम् ।
संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो[१] मि॒त्राण्य॑र्बुदे ॥ २ ॥

उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्राः॑ । देव॑ऽजनाः । यू॒यम् ।

---

१ KK̆^m V नो॒ मित्रा॒ण्य॑°. We with ABB̆^h CDERS̆^m Cs.

---

1 S' अर्बुदश्च.

सम्ऽदृष्टाः । गुप्ताः । वः । सन्तु । या । नः । मित्राणि । अर्बुदे ॥ २ ॥

हे मित्राः मित्रभूता अस्माकं जये प्रवृत्ता हे देवजनाः यूयम् उत्तिष्ठत अस्मात् सेनानिवेशाद् उद्गच्छत । "उदोनूर्ध्वकर्मणि" इति पर्युदस्तत्वाद् आत्मनेपदाभावः । सं नह्यध्वम् उत्थानानन्तरं युद्धाय संनद्धा भवत । तथा वः युष्माभिः संदृष्टाः सम्यङ्गिरीक्षिताः अस्मदीया भटाः गुप्ताः रक्षिताः सन्तु भवन्तु । व इति तृतीयार्थे षष्ठी । हे अर्बुदे सर्प नः अस्माकं या यानि मित्राणि अस्मदीयैः शत्रुभिः सह योद्धुम् आगतानि तानि त्वया गुप्तानि रक्षितानि भवन्त्वित्यर्थः ॥

तृतीया ॥

उत्तिष्ठतमा रभेथामादानसंदानाभ्याम् ।
अमित्राणां सेना अभि धत्तमर्बुदे ॥ ३ ॥

उत् । तिष्ठतम् । आ । रभेथाम् । आदानऽसंदानाभ्याम् ।
अमित्राणाम् । सेनाः । अभि । धत्तम् । अर्बुदे ॥ ३ ॥

हे अर्बुदे त्वं च न्यर्बुदिश्च युवाम् उत्तिष्ठतम् स्थानाद् उच्चलतम् । आ रभेथाम् युद्धम् उपक्रमेथाम् । रभ राभस्ये । राभस्यं कार्योपक्रम इति तद्वृत्तिः । अनन्तरम् आदानसंदानाभ्याम् आदीयते गृह्यते अनेनेति ग्रहणार्थं रज्जुयन्त्रम् आदानम् । संदीयते बध्यते अनेनेति संदानं बन्धनरज्जुः । ताभ्यां रज्जुभ्याम् अमित्राणां शत्रूणां संबन्धिनीं सेनाम्[1] अभि धत्तम् बध्नीतम् ॥ अभिपूर्वो दधातिर्बन्धने वर्तते । यथा । "अश्वाभिधानीम् आदत्ते" इति [तै० सं० ५. १. २. १] ॥

अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।
याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।
ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥ ४ ॥

---

१ So P P[2] J Cp, and not सम्ऽदृष्टाः and गुप्ताः. २ P अर्बदे ।.

---

1 The text in S′ too reads सेनामभि for our सेना अभि.

अर्बुदिः[1] । नाम । यः । देवः । ईशानः । च । निऽअर्बुदिः[2] ।
याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही ।
ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥ ४ ॥

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
भञ्जन्नमित्राणां सेनां भोगेभिः परि वारय ॥ ५ ॥

उत् । तिष्ठ । त्वम् । देवऽजन । अर्बुदे[3] । सेनया । सह ।
भञ्जन् । अमित्राणाम् । सेनाम् । भोगेभिः । परि । वारय ॥ ५ ॥

चतुर्थी ॥ अर्बुदिन्यर्बुद्योर्माहात्म्यम् अनया प्रतिपाद्यते । अर्बुदिरिति प्रसिद्धः सर्पात्मको यो देवः तथा ईशानः सर्वस्य ईशिता यश्च न्यर्बुदिरिति प्रसिद्धः सर्पः याभ्याम् अर्बुदिन्यर्बुदिभ्याम् अन्तरिक्षं सर्वम् आवृतम् स्वशरीरैरावेष्टितम् इयं परिदृश्यमाना मही महती पृथिवी च याभ्याम् आवृता । तौ सर्पात्मकौ देवौ संग्रामजयकर्मणि सर्वोत्कर्षेण वर्तेते इत्यर्थः ॥

पञ्चमी ॥ ताभ्यां द्यावापृथिव्यौ व्याप्य वर्तमानाभ्याम् इन्द्रमेदिभ्याम् इन्द्रस्य स्निग्धाभ्याम् । ञिमिदा स्नेहने । अस्मात् ताच्छीलिको णिनिः । अर्बुदिन्यर्बुदिभ्यां जितं शत्रुबलम् अहं पश्चात् सेनया अन्वेमि अनुगच्छामि । हे देवजन देवजातीय अर्बुदे त्वं सेनया आत्मीयया सह उत्तिष्ठ उद्गच्छ । शत्रून् प्रथमम् अभियाहीत्यर्थः । अनन्तरम् अमित्राणाम् शत्रूणां सेनां भञ्जन् आमर्दयन् भग्नवीर्यां कुर्वन् भोगेभिः भोगैः आत्मीयैः सर्पशरीरैः परि वारय परिवेष्टय । यथा शत्रुसेना अस्मान् न पश्यति तथा तदीयानि अक्षीणि पिधेहीत्यर्थः ॥

षष्ठी ॥

सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।

---

१ P अर्बदिः ।. We with P̊ J Cp. २ P °अर्बदिः ।. We with P̊ J Cp. ३ P अर्बदे ।. We with P̊ J Cp.

तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥ ६ ॥

सप्त । जातान् । निऽअर्बुदे । उत्ऽआराणाम् । सम्ऽईक्षयन् ।
तेभिः । त्वम् । आज्ये । हुते । सर्वैः । उत् । तिष्ठ । सेनया ॥ ६ ॥

हे न्यर्बुदे एतत्संज्ञ सर्प उदाराणाम् प्रागुक्तलक्षणानां मध्ये सप्तसंख्याकान् जातान् उत्पन्नान् दृष्टितिरोधायकान् समीक्षयन् शत्रूणां दर्शयंस्त्वम् आज्ये हुते । उपलक्षणम् एतत् । आज्योपलक्षितेषु द्रव्येषु हुतेषु सत्सु तेभिः तैः सर्वैरुपलक्षितः सन् अस्मदीयया सेनया सह उत्तिष्ठ उद्गच्छ ॥

सप्तमी ॥

प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
विकेशी पुरुषे हते रदिते अर्बुदे[1] तव ॥ ७ ॥

प्रतिऽघ्नाना । अश्रुऽमुखी । कृधुऽकर्णी । च । क्रोशतु ।
विऽकेशी । पुरुषे । हते । रदिते । अर्बुदे । तव ॥ ७ ॥

हे अर्बुदे तव रदिते दन्तैर्विलेखने खादने सति तथा[2] तेन रदनेन शत्रुभूते पुरुषे हते मृते सति तदीया जाया प्रतिघ्नाना प्रतिमुखं स्वकीयं वक्षस्ताडयन्ती । ॥ प्रतिपूर्वात् हन्तेर्लटः शानच् । "गमहन०" इति उपधालोपः ॥ । अश्रुमुखी बाष्पमुखी कृधुकर्णी । कृध्विति ह्रस्वनाम । कर्णाभरणपरित्यागेन ह्रस्वकर्णी च विकेशी विकीर्णशिरोरुहा च सती क्रोशतु रोदनं करोतु । ॥ क्रुश आह्वाने रोदने च ॥ ॥

अष्टमी ॥

संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।
पतिं भ्रातरमात्स्वान् रदिते[2] अर्बुदे तव ॥ ८ ॥

सम्ऽकर्षन्ती[3] । करूकरम् । मनसा । पुत्रम् । इच्छन्ती ।

---

१ B अर्बुदे. २ B Cs रदिते. ३ P °कर्षती ।. We with P[2] J Cp.

---

1 S′ दृष्टतिरो°. 2 S′ om. तथा ते°.

पतिम् । भ्रातरम् । आत् । स्वान् । रदिते । अर्बुदे । तव ॥ ८ ॥

हे अर्बुदे तव त्वदीये रदिते रदने दन्तैर्विलेखने सति विषावेशवशात् शत्रुस्त्री करूकरं संकर्षन्ती । करु इति अनुकरणशब्दोयम् । तत्करोतीति करूकरम् हस्तपादाद्यवयवगतं संधिमद् अस्थिजातं तत् सम्यक् कर्षन्ती । लोके हि भयवशाद् उभयोर्हस्तयोः परस्पराङ्गुलिनिपीडनेन तादृशं शब्दम् उत्पादयन्ति । तदनन्तरं मनसा अन्तःकरणेन विषप्रतीकाराय पुत्रम् आत्मीयं सुतम् इच्छन्ती । तदनन्तरं पतिम् भर्तारम् इच्छन्ती । [ततो] भ्रातरम् आत्मीयं सहजम् । आत् अनन्तरं स्वान् स्वकीयान् बन्धुजनान् विषनिर्हरणाय इच्छन्ती । इत्थम् इतिकर्तव्यतामूढा भवत्वित्यर्थः ॥

नवमी ॥

अलिक्लवा जाष्कमदा[१] गृध्राः श्येनाः पतत्रिणः ।
ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ ९ ॥

अलिक्लवाः । जाष्कमदाः[१] । गृध्राः । श्येनाः । पतत्रिणः ।
ध्वाङ्क्षाः । शकुनयः । तृप्यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥ ९ ॥

अलिक्लबाः* । विशिष्टक्लैब्ययुक्ता विक्लबाः तद्विपरीता अलिक्लबाः । धृष्टाः पक्षिण इत्यर्थः । यांश्च* पक्षिजातयः क्लमदाः* क्लमस्य शरीरावसादस्य दात्र्यः । तां[2] अनुक्रामति । गृध्राः श्वेतवर्णा मांसाभिलाषिणः पक्षिणः । श्येनाः प्रसिद्धाः । पतत्रिणः अन्ये च मांसभक्षकाः पक्षिणः पतत्रिशब्देन विवक्षिताः । ध्वाङ्क्षाः काकाः । एवमात्मकाः शकुनयः हे अर्बुदे तव रदिते त्वदीये रदने विषदन्तैर्विलेखने अमित्रेषु अस्मदीयेषु शत्रुषु सति स-

---

१ B जाःक्रमदा. A D K $\overset{m}{\text{S}}$ V Cs जाःकमदा. Sâyaṇa याः क्लमदा. K V whose reading is of course taken from Sâyaṇa recite °क्लंबा याः क्लमदा (!) instead of °क्लंबा याः क्लंमदा, because Sâyaṇa is unaccented. Sâyaṇa's text is not good. It probably arose originally from mispronunciation of ज for य. P $\overset{2}{\text{P}}$ J जाष्कमदाः ।. Cp जाःकमदाः ।. We with C R $\overset{m}{\text{K}}$ Dc and P $\overset{2}{\text{P}}$ J.

---

1 S′ करूषकरं. 2 S′ तावानु° (*sic*) for ता अनु°.

मीक्षयन् । ॥ व्यत्ययेन एकवचनम् ॥ । तन्मरणं प्रतीक्षमाणास्तदनन्तरं तद्भक्षणेन तृप्यन्तु तृप्ता भवन्तु ॥

दशमी ॥

अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
पौरुषेयेधि कुणपे रदिते अर्बुदे तव ॥ १० ॥ (२५)

अथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमिः ।
पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥ १० ॥ (२५)

अथो अपि च सर्वं श्वापदम् शुनः पदानीव पदानि यस्य सृगालव्याघ्रादेः तत् सर्वं श्वापदम् । मक्षिका मांसनिषेविणी या नीलमक्षिकेति प्रसिद्धा । क्रिमिः मांसेषु जीर्णेषु जायमानः प्राणी । एतत् सर्वम् हे अर्बुदे तव रदिते सति पौरुषेये पुरुषसंबन्धिनि कुणपे शवशरीरे अधि उपरि तृप्यतु । तव खादनेन सर्वेषु शत्रुषु मृतेषु तच्छरीराणि गृध्रादयः पक्षिश्वसृगालादयश्च भक्षयन्त्वित्यर्थः ॥

[इति] पञ्चमेनुवाके प्रथमं सूक्तम् ॥

"आ गृह्णीतम्" इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ॥

द्वितीयसूक्ते प्रथमा ॥

आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ ११ ॥

आ । गृह्णीतम् । सम् । बृहतम् । प्राणापानान् । निऽअर्बुदे ।
निऽवाशाः । घोषाः । सम् । यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते ।
अर्बुदे । तव ॥ ११ ॥

हे न्यर्बुदे त्वं च अर्बुदिश्च युवां शत्रुसंबन्धिनः प्राणापानान् आ गृह्णीतम् आसमन्तात् स्वीकुरुतम् । तदनन्तरं सं बृहतम् समूलम् उत्खिदतम् । ॥ वृहू उद्यमने । तुदादित्वात् शप्रत्ययः ॥ ॥ हे अर्बुदे

१ P Cp क्रमिः ।. We with P̊ J. २ P̊ J वृहतम् ।. We with P Cp.

तव रदिते सति अमित्रेषु शत्रुषु तद् रदितं समीक्षयन् । षष्ठ्यर्थे प्रथमा । समीक्षयतां जनानां निवाशाः नीचीनं वाश्यमाना आभाष्यमाणा घोषाः शब्दाः सं यन्तु सम्यग्वर्तन्ताम् । विषनिपीडितानाम् आर्तस्वरा उत्पद्यन्ताम् इत्यर्थः ॥

द्वितीया ॥

उद् वेपय सं विजन्तां भिया[1]मित्रान्त्सं सृज ।
उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥ १२ ॥

उत् । वेपय । सम् । विजन्ताम् । भिया । अमित्रान् । सम् । सृज ।
उरुऽग्राहैः । बाहुऽअङ्कैः । विध्य । अमित्रान् । निऽअर्बुदे ॥ १२ ॥

हे न्यर्बुदे एतत्संज्ञ सर्पजातीय देव अमित्रान् अस्मदीयान् शत्रून् उद् वेपय उत्कम्पय । टुवेपृ कम्पने इति धातुः । ते च अनन्तरं सं विजन्ताम् भयात् स्वस्थानात् प्रचलिताः उद्विग्ना भवन्तु । ओविजी भयचलनयोः । भिया अस्मत्सकाशाज्जनितया भीत्या सं सृज संयोजय । तदनन्तरम् ऊरुग्राहैः ऊरूणां ग्रहणैः बाहुवङ्कैः बाहुना वक्रबन्धनैः अमित्रान् अस्मदीयान् शत्रून् विध्य ताडय ॥

तृतीया ॥

मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।
मै[2]षामुच्छेषि किं चन रदिते अर्बुदे तव ॥ १३ ॥

मुह्यन्तु । एषाम् । बाहवः । चित्तऽआकूतम् । च । यत् । हृदि ।
मा । एषाम् । उत् । शेषि । किम् । चन । रदिते । अर्बुदे । तव ॥ १३ ॥

हे अर्बुदे तव रदिते खादने सति एषां शत्रूणां बाहवः विषावेशवशाद् मुह्यन्तु मूढा व्यापारासमर्था भवन्तु । एषां शत्रूणां हृदि हृदये यत् चित्ताकूतम् चित्तेन संकल्पितम् अर्थजातं तदपि मुह्यतु मूढं विस्मृतं भवतु । यद्वा चित्तानि मनांसि आकूतानि कर्तव्यविशेषविषयास्तद्वृत्तयः । तत् सर्वं मुह्यतु । अपि च एषां शत्रूणां संबन्धि किं चन

---

१ K भ्रया°. We with A B B^h C K^m R S^m P P^2 J V Cs. २ B मैषा° for मैषा°.

किमपि रथतुरगहस्त्यादिलक्षणं बलं मा उच्छेषि उच्छिष्टम् अवशिष्टं मा भूत् । सर्वमपि त्वया हन्यताम् इत्यर्थः ॥

चतुर्थी ॥

प्रतिघ्नानाः सं धावन्तूरः पटूरावाघ्नानाः ।
अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥ १४ ॥

प्रतिऽघ्नानाः । सम् । धावन्तु । उरः । पटूरौ । आऽघ्नानाः ।
अघारिणीः । विऽकेश्यः । रुदत्यः । पुरुषे । हते । रदिते । अर्बुदे । तव ॥१४॥

हे अर्बुदे तव रदिते खादने सति पुरुषे स्वकीये भर्तरि हते सति तदीयाः स्त्रियः प्रतिघ्नानाः प्रतिमुखं स्वशरीरम् आघ्नत्यस्ताडयन्त्यः । तथा उरः वक्षःस्थलं पटूरौ तत्प्रदेशौ [च] आघ्नानाः हस्ताभ्याम् आताडयन्त्यः । विकेश्यः विकीर्णकेश्यः । अघारिणीः अघेन भर्तृवियोगजनितेन दुःखेन आर्ताः । रुदत्यः संजातरोदनाः सत्यः सं धावन्तु मृतपुरुषसमीपं शीघ्रं गच्छन्तु । "सर्तेर्वेगितायां गतौ धावादेशो वक्तव्यः" इति "पाघ्रा°" इत्यादिना धाव् आदेशः ॥

पञ्चमी ॥

श्वन्वतीरप्सरसो रूपका उतार्बुदे ।
अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ १५ ॥

श्वन्ऽवतीः । अप्सरसः । रूपकाः । उत । अर्बुदे ।
अन्तःऽपात्रे । रेरिहतीम् । रिशाम् । दुर्निहितऽएषिणीम् ।
सर्वाः । ताः । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् ।
च । प्र । दर्शय ॥ १५ ॥

१ V धावन्तूरः पटुरा°. K धावन्तूरश्चतुरा°. A B B^h C E K^m R P P^2 J धावन्तूरः पटौरा°. We with D S^m Cs. २ A B B^h C E ३ for १. We with D S^m K K^m V Cs. ३ P P^2 J पटौरौ. We with Cp.

1 S' हन्यंताम्.

श्वन्वतीः शुना क्रीडार्थेन सारमेयेण सहिता अप्सरसः गन्धर्वस्त्रियः । रूपकाः मायावशात् केवलं रूपमात्रेण उपलभ्यमानाः सेनारूपकाः । हे अर्बुदे ताः सर्वा अमित्रेभ्यो दर्शय । तथा पात्रे अन्तः मध्ये रेरिहतीम्[1] पुनःपुनर्लिहतीं[2] दुर्निहितैषिणीम् दुष्टनिक्षिप्तम् इच्छन्तीं वशाम् गाम् हे अर्बुदे त्वं सर्वास्ताः प्राग् उदीरिता अमित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कुरु । उदारान् उल्कापातादीन् अद्भुतान् विकृतदर्शनान् यक्षराक्षसांश्च प्र दर्शय ॥

खडूरेऽधिचङ्क्रमां[१] खर्विकां खर्ववासिनीम् ।
य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
सर्पा इतरजना रक्षांसि ॥ १६ ॥

खडूरे । अधिऽचङ्क्रमाम्[२] । खर्विकाम् । खर्वऽवासिनीम् ।
ये । उत्ऽआराः । अन्तःऽहिताः । गन्धर्वऽअप्सरसः । च । ये ।
सर्पाः । इतरऽजनाः[३] । रक्षांसि ॥ १६ ॥

चतुर्दंष्ट्रांछ्यावदतः[४] कुम्भमुष्कां[५] असृङ्मुखान् ।
स्वभ्यसा ये चोद्भ्यसाः ॥ १७ ॥

चतुःऽदंष्ट्रान् । श्यावऽदतः । कुम्भऽमुष्कान् । असृक्ऽमुखान् ।
स्वऽभ्यसाः । ये । च । उत्ऽभ्यसाः ॥ १७ ॥

षष्ठी ॥ दूरभूतं खं खडूरम् आकाशे दूरदेशे अधि उपरि चङ्क्रमाम् चङ्क्रमणशीलां मायावशाद् इतस्ततः प्रादुर्भवन्तीं [खर्विकाम् अल्पह्रस्वां खर्व]वाशिनीम् खर्वम् अल्पं शब्दायमानां मानवशात्[3] मितभाषमाणाम्[4] हे अर्बुदे त्वं शत्रुभ्यः प्र दर्शय यथा ते पराजयेरन् । ये उदाराः यक्षराक्षसादयः

१ K °चक्रमां. We with A B $\overset{h}{B}$ C D E $\overset{m}{K}$ R $\overset{m}{S}$ J V Cs. २ P $\overset{2}{P}$ °चक्रमाम् ।. We with J Cp. ३ P इतरऽजनाः ।. We with $\overset{2}{P}$ J Cp. ४ B °दंष्ट्रा°. K °दंष्ट्र्यां. We with A $\overset{h}{B}$ C D E $\overset{m}{K}$ R $\overset{m}{S}$ V Cs. ५ B $\overset{h}{B}$ °मुष्कां.

1 S′ रेरिहंती. The text too in S′ has रेरिहंती. 2 S′ °लिहंतीं. 3 मानावशात्. 4 S′ प्रतिभासमानाम्. The emendation is conjectural.

अन्तर्हिताः स्वमायया व्यवहिताः अस्मद्दृग्गोचरा न भवन्ति ये च गन्धर्वाप्सरसस्तथाविधाः तान् सर्वान् पराजयार्थं शत्रुभ्यो दर्शय ॥

सप्तमी ॥ सर्पाः सर्पस्वरूपाः इतरजनाः इतरजनसंज्ञका देवाः । यद्वा सर्पाः सर्पात्मका देवास्तदपेक्षया इतरजनाः तत्सदृशा देवजातयः । रक्षांसि राक्षसाः । ते च चतुर्दंष्ट्राः दंशनसाधनचतुर्दन्तयुक्ताः । तान् । श्यावदतः श्यामवर्णदन्तयुक्तान् । एतानपि मायामयान् अमित्रेभ्यो दर्शय । तथा [कुम्भमुष्कान् कुम्भा]कृतिमुष्कयुक्तान् । असृङ्मुखान् रक्तास्यान् । स्वभ्यसाः स्वायत्तभीतयो राक्षसाः । ये च उद्भ्यसाः उन्नतभीतयः । ॥भ्यस भये । "घञर्थे कविधानम्" इति कप्रत्ययः॥ । घोरेण रूपेण इत्थं विविधभयजनका राक्षसा इत्यर्थः । तान् सर्वान् अमित्रेभ्यो मायया दर्शय ॥

अष्टमी ॥

उद् वे॑पय॒ त्वम॑र्बुदे॒[1]ऽमित्रा॑णाम॒मूः सिचः॑ ।
जयां॑[3]श्च जि॒ष्णुश्चा॒मित्राँ॒[4] जय॑ता॒मिन्द्र॑मेदिनौ ॥ १८ ॥

उत् । वे॒प॒य॒ । त्वम् । अ॒र्बु॒दे॒ । अ॒मित्रा॑णाम् । अ॒मूः । सिचः॑ ।
जय॑न् । च॒ । जि॒ष्णुः । च॒ । अ॒मित्रा॑न् । जय॑ताम् । इन्द्र॑ऽमेदिनौ ॥१८॥

हे अर्बुदे त्वम् अमित्राणाम् शत्रूणाम् अमूः सेनाः शुचः[2] शोचमाना विषावेशजनितशोकार्ताः उद् वेपय उत्कम्पय । ॥शुच शोके । अस्मात् "क्विप् च" इति क्विप्॥ । तथा अमित्रान् शत्रून् जयन् पराभावयन् जिष्णुः जयशीलश्च अर्बुदिन्यर्बुदी इन्द्रमेदिनौ इन्द्रेण सह स्निह्यन्तौ जयताम् अस्माकं जयं कुरुताम् ॥

नवमी ॥

प्रब्लीनो मृदि॒तः श॑यां ह॒तो॒३॒॑ऽमित्रो॑ न्यर्बुदे ।

१ B °दे अमित्रा° for °देमित्रा°. We with A K K^m B^h C D E R S^m V Cs. २ K V शुचः. We with K^m B^h A C D E R S^m P P^2 J V Cs Cp. ३ Sâyaṇa's text and K V जयंश्च. We with A B C B^h D E K^m R S^m V Cs. ४ B °मित्रां. B^h K K^m V Cs °मित्रान्. ५ Cp जयान्. We with P P^2 J. The य seems to be lengthened in the Saṁhitâ.

अ॒ग्नि॒जि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु सेन॑या ॥ १९ ॥

प्रऽव्लीनः । मृ॒दि॒तः । श॒या॒म् । ह॒तः । अ॒मित्रः॑ । नि॒ऽअ॒र्बु॒दे॒ ।

अ॒ग्नि॒ऽजि॒ह्वाः । धू॒म॒ऽशि॒खाः । जय॑न्तीः । य॒न्तु॒ । सेन॑या ॥ १९ ॥

हे न्यर्बुदे अमित्रः अस्मदीयः [शत्रुः] प्रव्लीनः प्रभीतः मृदितः संपिष्टगात्रः हतः गतासुः शयाम् शेताम् । "लोपस्त आत्मनेपदेषु" इति तलोपः । व्ली भये । अस्मात् प्रपूर्वात् कर्मणि निष्ठा । तकारस्य नत्वम् । अग्निजिह्वाः अग्नेर्ज्वालाः धूमशिखाः धूमप्ररोहाः मायावशात् त्वयोत्पादिताः जयन्तीः शत्रुबलं जयन्त्यः सेनया अस्मदीयया सह यन्तु गच्छन्तु ॥

दशमी ॥

तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ।

अ॒मित्रा॑णां शचीपति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥ २० ॥ (२६)

तया॑ । अ॒र्बु॒दे॒ । प्रऽनु॑त्तानाम् । इन्द्रः॑ । ह॒न्तु॒ । वरं॑ऽवरम् ।

अ॒मित्रा॑णाम् । श॒ची॒ऽपतिः॑ । मा । अ॒मीषा॑म् । मो॒चि॒ । कः॒ । च॒न ॥ २० ॥

हे अर्बुदे त्वया प्रणुत्तानाम् युद्धरङ्गात् प्रच्यावितानाम् । "नसत्तनिषत्तानुत्तप्रतूर्त°" इति निपातनात् निष्ठानत्वाभावः । अमित्राणाम् शत्रूणां शचीपतिः शच्याः पतिः इन्द्रः वरंवरम् श्रेष्ठंश्रेष्ठं हन्तु मारयतु । अमीषां शत्रूणां मध्ये कश्चन कश्चिदपि मा मोचि[1] मा मुच्यताम् क्रमशः सर्वो हन्यताम् इत्यर्थः । मुच्ऌ मोक्षणे इत्यस्मात् कर्मणि माङि लुङ् । "चिण् भावकर्मणोः" इति च्लेश्चिण् आदेशः । "चिणो लुक्" इति तशब्दस्य लुक् ॥

[इति] पञ्चमेनुवाके द्वितीयं सूक्तम् ॥

"उत् कसन्तु हृदयानि" इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ॥

तत्र प्रथमा ॥

उत्क॑सन्तु हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु ।

1 S′ omits °चि मा मुच्यताम् and has a blank space for about seven letters instead.

शौष्कास्यमनु वर्ततामुमित्रान् मोत मित्रिणः ॥ २१ ॥

उत । कसन्तु । हृदयानि । ऊर्ध्वः । प्राणः । उत् । ईषतु ।

शौष्कऽआस्यम् । अनु । वर्तताम् । अमित्रान् । मा । उत । मित्रिणः॥२१॥

शत्रूणां संबन्धीनि हृदयानि अन्तःकरणानि उत् कसन्तु शरीराद् उद्गच्छन्तु । तथा प्राणः प्राणवायुः ऊर्ध्वः सन् उदीषतु शत्रुशरीरान्निर्गच्छतु । ॥ ईष गतौ ॥ । अमित्रान् शत्रून् शौष्कास्यम् शुष्कास्यता । भीतिवशाद् आस्यस्य निर्द्रवत्वम् । तद् अनु वर्तताम् अनुगच्छतु । आस्यशोषणेन शत्रवो म्रियन्ताम् इत्यर्थः । अपि च मित्रिणः अस्माकं मित्रभूतान् जनान् मा अनुवर्तताम् । तेषाम् आस्यशोषो मा भूद् इत्यर्थः ॥

द्वितीया ॥

ये च धीरा ये चाधीराः परांञ्चो बधिराश्च ये ।

तमसा[1] ये च तूपरा अथो[2] बस्ताभिवासिनः ।

सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ २२ ॥

ये । च । धीराः । ये । च । अधीराः । परांञ्चः । बधिराः । च । ये ।

तमसाः[3] । ये । च । तूपराः । अथो इति । बस्तऽअभिवासिनः[4] ।

सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च ।

प्र । दर्शय ॥ २२ ॥

ये च धीराः शूरा भटाः ये च अधीराः अशूराः कातराः । पराञ्चः पराङ्मुखा युद्धात् पलायमानाः ये च बधिराः भयवशात् हतश्रवणसामर्थ्याः । तमसा* मोहेन ये च तूपराः तूपरः शृङ्गहीनः पशुः । तद्वद् अवस्थिताः । अथो अपि च बस्ताविवाशिनः* बस्ताश्च अवयश्च बस्तावयः तद्वद् वाशितुं शीलम् एषां ते बस्ताविवाशिनः । बस्ताविध्वनिं

---

१ So A B B^h C D E K K^m R S^m V Cs. Sâyaṇa interprets तमसा, which is inferior to the MSS. २ So A B B^h C D E K K^m R S^m P P^2 J Cp V Cs. ३ So P P^2 J Cp. ४ So P P^2 J Cp.

कुर्वाणा इत्यर्थः । हे अर्बुदे त्वं सर्वांस्तान् स्वमायया उद्भावितान् अमित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कुरु पराजयार्थम् । गतम् अन्यत् ॥

तृतीया ॥

अर्बुदिश्च त्रिषंधिश्चामित्रान् नो वि विध्यताम्।
यथैषामिन्द्र वृत्रहन् हनाम शचीपतेमित्राणां सहस्रशः ॥ २३ ॥

अर्बुदिः । च । त्रिऽसंधिः । च । अमित्रान् । नः । वि । विध्यताम् ।
यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽशः ॥ २३ ॥

[त्रिषंधिः] कश्चित् सेनामोहको देवः संधित्रयोपेतवज्रायुधाभिमानी वा । स च अर्बुदिश्च उभौ नः अस्माकम् अमित्रान् शत्रून् वि विध्यताम् विविधं ताडयताम् । हे वृत्रहन् वृत्रस्य हन्तरिन्द्र हे शचीपते शच्या देव्याः पते यथा येन प्रकारेण एषाम् अमित्राणाम् शत्रूणां संबन्धिनो जनान् सहस्रशः सहस्रसंख्याकान् एकोद्योगेन हनाम मारयाम । तथा वि विध्यताम् इति संबन्धः । ⌛ "संख्यैकवचनाच्च वीप्सायाम्" इति सहस्रशब्दात् शस् प्रत्ययः ⌛ ॥

चतुर्थी ॥

वनस्पतीन् वानस्पत्यानोषधीरुत वीरुधः ।
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ २४ ॥

वनस्पतीन् । वानस्पत्यान् । ओषधीः । उत । वीरुधः ।
गन्धर्वऽअप्सरसः । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् ।
सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्यः । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥ २४ ॥

---

१ K अथैषा°. We with A B B̊ C D E K̊ R S̊ P P̊ J Cp V Cs. २ B̊ Cs सर्वास्तां.
३ P उग्र. We with P̊ J Cp.

---

1 S' °मोक्षको.

वनस्पतीन् वृक्षान् । वानस्पत्यान् वनस्पतिविकारान् । ओषधीः व्रीहियवाद्याः । [उत] वीरुधः विरोहणशीला आरण्याः । गन्धर्वाप्सरसः गन्धर्वान् अप्सरसश्च सर्पान् विकृतवेषान् भुजङ्गान् देवान् पुण्यजनान् यक्षान् पितॄन् मृतान् पूर्वपुरुषान् मायामयान् । तान् सर्वान् हे अर्बुदे त्वं शत्रुभ्यो दृष्टिविषयान् कुरु । उक्तार्थम् अन्यत् ॥

पञ्चमी॥

ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।
ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ २५ ॥

ईशाम् । वः । मरुतः । देवः । आदित्यः । ब्रह्मणः । पतिः ।
ईशाम् । वः । इन्द्रः । च । अग्निः । च । धाता । मित्रः । प्रजाऽपतिः ।
ईशाम् । वः । ऋषयः । चक्रुः । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे ।
तव ॥ २५ ॥

हे शत्रवः वः युष्माकं मरुदाद्या[1] देवाः । प्रत्ययश्रवणसामर्थ्यात् चक्रुरिति अन्ते श्रूयमाणं सर्वत्र संबध्यते । ईशां चक्रुः ईश्वराः शिक्षका भवन्तु । तथा इन्द्रश्च अग्निश्च इत्यनुक्रान्ताश्च देवाः हे शत्रवः [वः] युष्मान् ईशां चक्रुः ईश्वराः युष्माकं नियन्तारो भवन्तु । तथा ऋषयः अथर्वाङ्गिरःप्रभृतयः ईशां चक्रुः ईश्वराः शिक्षका भवन्तु । ⌛ईश ऐश्वर्ये । "इजादेश्च गुरुमतोनृच्छः" इति आम् प्रत्ययः । "आम्प्रत्ययवत् कृञोनुप्रयोगस्य" इत्यनुप्रयुज्यमानस्य करोतेः आत्मनेपदाभावश्छान्दसः⌛ । हे अर्बुदे अमित्रेषु अस्मदीयेषु शत्रुषु तव रदिते दन्तैर्विलेखने खादने सति तत् समीक्षयन् । ⌛व्यत्ययेन एकवचनम्⌛ । अवलोकयन्तो देवाद्याः । ईशां चक्रुः इति संबन्धः ॥

१ B ऋषय°.

1 S' मरुताद्या.

षष्ठी ॥

तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥ २६ ॥ (२७)

तेषाम् । सर्वेषाम् । ईशानाः । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्राः ।
देवऽजनाः । यूयम् ।

इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥ २६ ॥

तेषां सर्वेषाम् अस्मदीयानां शत्रूणाम् ईशानाः ईश्वराः शिक्षकाः [सन्तः उत्तिष्ठत सं नह्यध्वं च तेषां शिक्षणाय उत्थाय संनद्धा भवत] । हे मित्रा देवजनाः यूयम् इमम् अस्मदीयं प्रस्तुतं संग्रामं संजित्य सम्यग् जित्वा अस्मदीयान् शत्रून् निरस्य यथालोकम् यथास्थानं वि तिष्ठध्वम् । स्वस्वं स्थानं गच्छतेत्यर्थः । ⌛ "समवप्रविभ्यः स्थः" इति आत्मनेपदम् ⌛ ॥

[इति] पञ्चमेनुवाके तृतीयं सूक्तम् ॥

"उत्तिष्ठत" इति सूक्तस्य शत्रुजयकर्मणि संप्रेषणादिषु विनियोग उक्तः ॥

तत्र प्रथमा ॥

उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।
सर्पा इतरजना रक्षांस्यमित्राननु धावत ॥ १ ॥

उत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआराः । केतुऽभिः । सह ।
सर्पाः । इतरऽजनाः । रक्षांसि । अमित्रान् । अनु । धावत ॥ १ ॥

हे उदाराः औदार्यगुणोपेताः सेनानायकाः केतुभिः आत्मीयैर्ध्वजैः सह उत्तिष्ठत युद्धार्थम् उद्गच्छत सं नह्यध्वम् संनद्धाः कवचादिभिः संबद्धा युद्धोद्युक्ता भवत । यद्वा उदाराः पूर्वोक्ता मायामया अद्भुतरूपा यातुधानाद्याः । तेत्र संबोध्याः ॥ सर्पाः हे सर्पाकृतयो देवजनाः । इ-

---

१ So we divide with A B B^h C D E K K^m R S^m P P^2 J Cp V Cs Dc. See Rw.

तरजनाः सर्पव्यतिरिक्ता देवजातयः एतत्संज्ञाः । हे रक्षांसि राक्षसाः यूयमपि अस्मदीयान् अमित्रान् शत्रून् अनु धावत अनु पृष्ठतः शीघ्रं गच्छत ॥

ईशां वो वेद राज्यं त्रिषंधे अरुणैः केतुभिः सह ।
ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।
त्रिषंधेस्ते[1] चेतसि दुर्णामान उपासताम् ॥ २ ॥

ईशाम् । वः । वेद[2] । राज्यम् । त्रिऽसंधे । अरुणैः । केतुऽभिः । सह ।
ये । अन्तरिक्षे । ये । दिवि । पृथिव्याम् । ये । च । मानवाः ।
त्रिऽसंधेः । ते[3] । चेतसि । दुःऽनामानः । उप । आसताम् ॥ २ ॥

अयोमुखाः सूचीमुखा[4] अथो विकङ्कतीमुखाः ।
क्रव्यादो वातरंहस आ संजन्त्वमित्रान् वज्रेण त्रिषंधिना ॥ ३ ॥

अयःऽमुखाः । सूचीऽमुखाः[5] । अथो इति । विकङ्कतीऽमुखाः ।
क्रव्यऽअदः । वातऽरंहसः । आ । सजन्तु । अमित्रान् । वज्रेण । त्रिऽसंधिना ॥ ३ ॥

द्वितीया ॥ हे अमित्राः वः युष्माकं राज्यम् राष्ट्रं त्रिसंधिर्वज्राभिमानी देवः ईशां वेद ईशितव्यत्वेन जानातु । युष्मत्तः अपहृत्य स्ववशं करोत्वित्यर्थः । ⧖ ईश ऐश्वर्ये । "इजादेश्च गुरुमतः°" इति पूर्ववद् आम् प्रत्ययः । कृभ्वस्तिव्यतिरिक्तस्य विदेरनुप्रयोगश्छान्दसः ⧖ । हे त्रिसंधे वज्रात्मक देव अरुणैः अरुणवर्णैः केतुभिः आत्मीयैर्ध्वजैः सह । उत्तिष्ठेति शेषः । ये केतवः अन्तरिक्षे उत्पातरूपेण प्रादुर्भवन्ति ये च [दिवि] द्युलोके ये च पृथिव्याम् भूलोके मानवाः मनुष्यसंबन्धिनः केतवः । तैः केतुभिः सहेति पूर्वत्र संबन्धः ॥

---

१ K °धेस्त्वे. K^m °धेस्थे. V °धेत्वे. We read °धेस्ते with A B C D E B^h R S^m P P^2 J Cs Cp Dc. २ P P^2 J Cp वेद्ऽराज्यम् ।. We with Sâyaṇa. ३ So P P^2 J Cp. ४ So A B B^h C D E K K^m R S^m V Cs Dc. ५ P शुची°. P^2 J शूची°. We with Cp.

तृतीया ॥ हे त्रिसंधे* त्वे[1]* तव चेतसि मनसि[2] वर्तमानं [दुर्णामानम्*[3]] दुष्टसंज्ञकम् अस्मदीयं शत्रुम् उपासताम् संभजन्ताम् । के पुनस्त इत्याह । अयोमुखाः अयःसदृशतुण्डयुक्ताः पक्षिणः । सूचीमुखाः सूच्याकारतुण्डयुक्ताः पक्षिणः । अथो अपि च विकङ्कतीमुखाः विकङ्कतः बहुकण्टको वृक्षविशेषः । ⧖ "छन्दसीवनिपौ°" इति मत्वर्थीय ईकारः ⧖ । विकङ्कतवद् बहुकण्टक[युक्त][4]मुखाः पक्षिविशेषाः ॥ क्रव्यादः क्रव्यम् आममांसम् अदन्ति भक्षयन्तीति क्रव्यादो गृध्रादयः । ⧖ "क्रव्ये च" इति अद भक्षणे इत्यस्माद् विट् प्रत्ययः ⧖ । वातरंहसः वातवेगाः त्रिसंधिना एतत्संज्ञेन देवेन वज्रेण वज्रायुधाभिमानिना प्रेरिताः सन्तः अमित्रान् अस्मदीयान् शत्रून् आ सजन्तु आसक्ता भवन्तु । यद्वा संधित्रयोपेतेन वज्रायुधेन आसक्तान् संबद्धान् कुर्वन्तु । यथा ते वज्रेण हन्येरन् तथा प्रयतन्ताम् इत्यर्थः । यस्य हि निकटे एवंरूपाः पक्षिण उपसर्पन्ति तस्य मरणम् अवश्यं भवतीति शाकुनिकशास्त्रप्रसिद्धिः ॥

चतुर्थी ॥

अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।
त्रिषंधेरियं सेना[१] सुहितास्तु मे वशे ॥ ४ ॥

अन्तः । धेहि । जातऽवेदः । आदित्य । कुणपम् । बहु ।
त्रिऽसंधेः । इयम् । सेना[२] । सुऽहिता । अस्तु । मे । वशे ॥ ४ ॥

हे जातवेदः जातानां वेदितः सांग्रामिकाग्ने आदित्य । ⧖ "सुपां सुलुक्°" इति विभक्तेर्लुक् ⧖ । आदित्यम् दिवि वर्तमानं सूर्यं बहु बहुलं कुणपम् । ⧖ तृतीयार्थे द्वितीया ⧖ । बहुलेन शवशरीरेण अन्तरिक्षे निपद्यमानेन अन्तर्धेहि आच्छादय । त्रिषंधेर्देवस्य संबन्धिनी इयं सेना मे मम वशे सुहितास्तु सम्यग् निहितास्तु । तया वयं शत्रून् जयेमैवेत्यर्थः ॥

---

१ So A B B^h C D E K K^m R S^m V Cs Dc. २ P P^2 J सेनाः।. We with Cp.

---

1 The text in S′ reads त्रिसंधे त्वे in place of our त्रिषंधेस्ते. 2 S′ repeats again. 3 The text in S′ has दुर्नामानमुपा°. 4 S′ has space for two letters instead of °युक्त°.

पञ्चमी ॥

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
अयं बलिर्व आहुतस्त्रिषंधेराहुतिः प्रिया ॥ ५ ॥

उत् । तिष्ठ । त्वम् । देवऽजन[1] । अर्बुदे । सेनया । सह ।
अयम् । बलिः । वः । आऽहुतः । त्रिऽसंधेः । आऽहुतिः । प्रिया ॥ ५ ॥

हे देवजन देवजातीय अर्बुदे त्वम् आत्मीयया सेनया सह उत्तिष्ठ उद्गच्छ । हे अर्बुदे आहुतिः* हूयमानः पृषदाज्यहोमः वः युष्माकम् अयं बलिः तृप्तिकरो हविर्भागः । यतो बलिप्रियास्त्वदीयाः सर्पाः अतोऽस्मदीयं हूयमानं पृषदाज्यं स्वीकृत्य अस्मदीयान् शत्रून् मारयन्तु इत्यर्थः । तथा त्रिषंधेर्देवस्य या सेना प्राग् उक्ता सापि आहुतिप्रिया[1]* अनयाहुत्या प्रीता सती शत्रून् हिनस्तु ॥

षष्ठी ॥

शितिपदी सं द्यतु[2] शरव्ये3यं चतुष्पदी ।
कृत्येमित्रेभ्यो भव त्रिषंधेः सह सेनया ॥ ६ ॥

शितिऽपदी । सम् । द्यतु[3] । शरव्या । इयम्[4] । चतुःऽपदी ।
कृत्ये । अमित्रेभ्यः । भव । त्रिऽसंधेः । सह । सेनया ॥ ६ ॥

शितिः श्वेतवर्णः पादे यस्याः सा शितिपदी गौः । सेयं चतुष्पदी पादचतुष्टयोपेता शरव्या शरूणां बाणानां समूहः शरव्या । ⌛ "पाशादिभ्यो यः" इति समूहेर्थे यप्रत्ययः ⌛ । शरसंहतिरूपा भूत्वा सं पततु*[2] शत्रून् संप्राप्नोतु । हे कृत्ये कृत्यारूपिणि शितिपदि त्वम् अमित्रे-

१ P̊[2] °जना । We with J P Cp. २ So A B B̊[h] C D E K K̊[m] R S̊[m] P P̊[2] J Cp V Cs Dc.
३ So P P̊[2] J Cp. ४ P इदम् । We with P̊[2] J Cp.

1 Sâyaṇa's readings in this verse are inferior to ours. He could easily have changed and improved them, and the fact that he did not do so shows that he faithfully adhered to his text such as it was. 2 The text in S′ has पततु for our द्यतु.

भ्यः शत्रुभ्यः कृत्यारूपा संहर्त्री भव । त्रिषंधेर्देवस्य सेनया सह । सेनापि तव सहायभूतेत्यर्थः ॥

सप्तमी ॥

धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।
त्रिषंधेः[1] सेनया जिते अरुणाः सन्तु केतवः ॥ ७ ॥

धूमऽअक्षी । सम् । पततु[2] । कृधुऽकर्णी । च । क्रोशतु ।
त्रिऽसंधेः । सेनया । जिते । अरुणाः । सन्तु । केतवः ॥ ७ ॥

शत्रुसंबन्धिनी सेना धूमाक्षी धूमेन मायामयेन आवृतानि अक्षीणि चक्षूंषि यस्याः सा तथोक्ता । "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्" इति षच् समासान्तः । "षिद्गौरादिभ्यश्च" इति ङीष् । तादृशी सती सं पततु सम्यग् निपद्यताम् । तथा कृधुकर्णी अल्पश्रोत्रा पटहध्वनिना हतश्रवणसामर्थ्या च सा परकीया सेना क्रोशतु आक्रोशतु । इतिकर्तव्यतामूढा भवतु । इत्थं त्रिषंधेर्देवस्य संबन्धिन्या सेनया परकीये बले जिते जेतव्ये सति तत्संबन्धिनः अरुणाः अरुणवर्णाः केतवः ध्वजाः सन्तु भवन्तु ॥ यद्वा धूमैरक्षीणि आवृण्वती कृत्या धूमाक्षी । सा सं पततु शत्रुसेनां समागच्छतु । तथा कृधुकर्णी । कृधु इति अल्पनाम । कर्णयोः अल्पत्वापादिका श्रवणशक्तेर्विहन्त्री कृत्या कृधुकर्णी । सा च भीत्युत्पादनाय क्रोशतु । एवं त्रिषंधेः सेनया परकीये बले जिते सति तदीयाः केतवः अरुणाः रुधिरेणाक्ताः अरुणवर्णा भवन्तु ॥

अष्टमी ॥

अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।
श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥ ८ ॥

अव । अयन्ताम् । पक्षिणः । ये । वयांसि । अन्तरिक्षे । दिवि । ये । चरन्ति ।

१ B^h omits the visarga. We with A B C D E K K^m R S^m V Cs Dc P P^2 J Cp. २ P^2 P J तपतु. We with Cp. It is पतंतु in A B B^h C D E K K^m R S^m Cs Dc. ३ B^h रंभन्ता°. We with A B C D E K K^m R S^m V Cs Dc.

श्वापदः । मक्षिकाः । सम् । रभन्ताम् । आमऽअदः । गृध्राः । कुणपे । रदन्ताम् ॥ ८ ॥

अथ जयानन्तरभावीनि कार्याणि प्रार्थ्यन्ते । अन्तरिक्षे आकाशे ये वयांसि पक्षिणः संचरन्ति ते पक्षिणः अवायन्ताम् मृते शत्रुबले मांसभक्षणाय अवाङ्मुखं निपद्यन्ताम् । ॥अय पय गतौ । अनुदात्तेत्त्वाद् आत्मनेपदम्॥ । तथा दिवि द्युलोके ये पक्षिणश्चरन्ति तेप्यवायन्ताम् । तथा श्वापदः शुनः पादा इव पादा येषां ते तथोक्ताः श्वसृगालादयः मक्षिकाश्च सं रभन्ताम् शत्रुसेनायां शवभक्षणार्थम् उपक्रमन्ताम् । तथा आमादः आममांसभक्षका गृध्राः पक्षिविशेषाः कुणपे शत्रुसेनासंबन्धिशवशरीरे रदन्ताम् स्वतुण्डैः पादैश्च विलिखन्तु । भक्षणाय उद्युञ्जताम् इत्यर्थः । ॥रद विलेखने॥ ॥

नवमी ॥

यामिन्द्रेण संधां समधत्थ्या[1] ब्रह्मणा च बृहस्पते ।
तयाहमिन्द्रसंधया सर्वान् देवानिह हुव इतो जयत मामुतः ॥ ९ ॥

याम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्थाः[2] । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया[3] । सर्वान् । देवान् । इह । हुवे । इतः । जयत । मा । अमुतः ॥ ९ ॥

हे बृहस्पते देव इन्द्रेण देवानाम् अधिपतिना ब्रह्मणा च तत्स्रष्ट्रा प्रजापतिना च यां संधाम् संधानक्रियां प्रतिज्ञारूपां[2] समधत्ताः[*3] । ॥छान्दसो वर्णविकारः॥ । संहितवान् असि । तथा च मन्त्रान्तरम् । "इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समधद्ध्वम्[4]" इति [तै° सं° १. ७. ८. ४] । हे इन्द्र[*] तया संधया[*] प्रतिज्ञारूपया संधानक्रियया सर्वान् देवान् इह अस्मिन् संग्रामे हुवे आह्वयामि । हे आहूता देवाः इतः

१ K A V समधत्ता. We with B B[h] C D E K[m] R S[m] P[2] J Cs Dc. २ P °अधत्ताः ।. We with P[2] J Cp. ३ So P P[2] J Cp.

1 S′ omit तेप्यवाय°. 2 S′ °रूपं. 3 S′ समधत्ता. 4 S′ समदध्वम्.

आसु अस्मदीयासु सेनासु जयत जयं कुरुत । अमुतः अमीषु परसेनासु मा जयत ॥

दशमी ॥

बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः[1] ।
असुरक्षयणं वधं त्रिषंधिं दिव्याश्रयन् ॥ १० ॥ (२८)

बृहस्पतिः । आङ्गिरसः । ऋषयः । ब्रह्मऽसंशिताः ।
असुरऽक्षयणम् । वधम्[2] । त्रिऽसंधिम् । दिवि । आ । अश्रयन् ॥ १० ॥

आङ्गिरसः अङ्गिरसः पुत्रो बृहस्पतिः देवमन्त्री ब्रह्मसंशिताः ब्रह्मणा मन्त्रेण स्वभ्यस्तेन तीक्ष्णीकृता अन्य ऋषयश्च असुरक्षयणम् असुराणां क्षयकरं वधम् हननसाधनम् आयुधं त्रिषंधिम् एतत्संज्ञं देवं संधित्रयोपेतं वज्रं वा दिवि द्युलोके स्थितम् आश्रयन् असेवन्त । समभजन्तेत्यर्थः ॥

[इति] पञ्चमेनुवाके चतुर्थं सूक्तम् ॥

"येनासौ गुप्त आदित्यः" इति सूक्तस्य शत्रुसेनाजयकर्मणि विनियोग उक्तः ॥

तत्र प्रथमा ॥

येनासौ[3] गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।
त्रिषंधिं देवा अभजन्तौजसे च बलाय च ॥ ११ ॥

येन । असौ । गुप्तः । आदित्यः । उभौ । इन्द्रः । च । तिष्ठतः ।
त्रिऽसंधिम् । देवाः । अभजन्त । ओजसे । च । बलाय । च ॥ ११ ॥

येन त्रिसंधिना असौ दूरे दिवि दृश्यमान आदित्यः गुप्तः रक्षितः असुरकृतोपद्रवपरिहारेण पालितः स आदित्य इन्द्रश्च उभौ येन त्रिसंधिना वज्रेण बलेन तिष्ठतः स्वस्थाने प्रतिष्ठितौ भवतः तं त्रिसंधिम् असुरक्षयणम् आयुधभूतं देवं देवाः सर्वे अभजन्त असेवन्त । किमर्थम् । ओ-

---

१ B^h °स्थिताः afterwards corrected into °शिताः. २ P वेधम् ।. ३ B येनासु. We with A B^h C D E K K^m R S^m V Cs Dc.

जसे ओजो नाम शरीरान्तर्गतो[1]ऽष्टमो धातुः । बलं तेजः । तस्मै च तत्कार्याय बलाय च । ⧗ उयभत्र तादर्थ्ये चतुर्थी ⧗ ॥

द्वितीया ॥

सर्वाँल्लोकान्त्समंजयन् देवा आहुत्यानया ।

बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥ १२ ॥

सर्वान् । लोकान् । सम् । अजयन् । देवाः । आऽहुत्या । अनया ।
बृहस्पतिः । आङ्गिरसः । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् ।
वधम् ॥ १२ ॥

देवाः इन्द्रादयः अनया आहुत्या अनेन पृषदाज्यहोमेन सर्वान् लोकान् समजयन् असुरान् निहत्य प्राप्नुवन् । आङ्गिरसः अङ्गिरसः पुत्रो बृहस्पतिः असुरक्षयणम् असुराणां क्षयकरं [यं] वधम् हननसाधनं वज्रम् आयुधम् असिञ्चत सेचनेन निर्मितवान् । पृषदाज्याहुतिरेव वज्रात्मना परिणतेत्यर्थः । अनया वज्ररूपया आहुत्येति पूर्वत्रान्वयः ॥

तृतीया ॥

बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।

तेनाहममूं सेनां नि लिम्पामि बृहस्पतेमित्रान् हन्म्योजसा ॥ १३ ॥

बृहस्पतिः । आङ्गिरसः । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ।
तेन । अहम् । अमूम् । सेनाम् । नि । लिम्पामि । बृहस्पते । अमित्रान् ।
हन्मि । ओजसा ॥ १३ ॥

पूर्वोर्धर्चः पूर्ववद् व्याख्येयः । हे बृहस्पते तेन त्वया निर्मितेन असुराणाम् अन्तकारिणा वज्रेण अहम् अमूः* शात्रवीः सेनाम् । ⧗ व्यत्ययेन एकवचनम् ⧗ । सेनाः नि लिम्पामि नितरां छिनद्मि । सेनाच्छेदनानन्तरं तदधिपतीन् अमित्रान् शत्रून् ओजसा आत्मीयेन बलेन नि हन्मि निहिनस्मि ॥

---

1 S′ omits °ष्टमो धातुः ।.

चतुर्थी ॥

सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।
इमां जुषध्वमाहुतिमितो जयत मामुतः ॥ १४ ॥

सर्वे । देवाः । अतिऽआयन्ति । ये । अश्नन्ति । वषट्ऽकृतम् ।
इमाम् । जुषध्वम् । आऽहुतिम् । इतः । जयत । मा । अमुतः ॥ १४ ॥

सर्वे इन्द्रादयो देवाः अत्यायन्ति शत्रून् अतिक्रम्य अस्मदभिमुखम् आगच्छन्ति । ते विशेष्यन्ते । ये देवा वषट्कृतम् वषट्कारेण दत्तं हविः अश्नन्ति भुञ्जते । ते सर्वे यूयम् इमाम् अस्मदीयाम् आहुतिं जुषध्वम् सेवध्वम् । तया प्रीता यूयम् इतः । ⌛सप्तम्यर्थे तसिल् प्रत्ययः⌛ । आसु अस्मदीयासु सेनासु जयत जयं कुरुत । अमुतः अमूषु परकीयासु सेनासु मा जयत । तत्र पराजय एव भवत्वित्यर्थः ॥

पञ्चमी ॥

सर्वे देवा अत्यायन्तु त्रिषंधेराहुतिः प्रिया ।
संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥ १५ ॥

सर्वे । देवाः । अतिऽआयन्तु । त्रिऽसंधेः । आऽहुतिः । प्रिया ।
सम्ऽधाम् । महतीम् । रक्षत । यया । अग्रे । असुराः । जिताः ॥ १५ ॥

सर्वे इन्द्रादयो देवाः अत्यायन्ति* शत्रून् अतिक्रम्य अस्मदभिमुखम् आगच्छन्तु । तथा त्रिसंधेः एतन्नाम्नः सेनामोहकस्य देवस्य इयम् अस्मदीया आहुतिः प्रिया प्रीतिकरी भवतु । हे देवाः संधाम् जयविषयप्रतिज्ञां महतीम् प्रौढां रक्षत । सा च त्रिसंधेराहुतिः तां प्रतिज्ञां रक्षतु । यया संधया अग्रे पूर्वं देवासुरयुद्धकाले असुरा जिताः पराजयं प्रापिताः । तां संधाम् इति पूर्वत्रान्वयः ॥

वायुरमित्राणामिष्वग्राण्याञ्चतु ।
इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।

आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥ १६ ॥

वायुः । अमित्राणाम् । इषुऽअग्राणि । आ । अञ्चतु ।
इन्द्रः । एषाम् । बाहून् । प्रति । भनक्तु । मा । शकन् । प्रतिऽधाम् । इषुम् ।
आदित्यः । एषाम् । अस्त्रम् । वि । नाशयतु । चन्द्रमाः । युताम् । अगतस्य । पन्थाम् ॥ १६ ॥

षष्ठी ॥ वायुर्देवः अमित्राणाम् शत्रूणाम् इष्वग्राणि इषूणाम् शराणाम् अग्राणि आञ्चतु[1] अभिमुखं गच्छतु । प्रतिकूलवातेन[2] लक्ष्यप्राप्तेः प्रागेव निपात्यन्ताम् इत्यर्थः । तथा इन्द्रो देवः एषां शत्रूणां बाहून् प्रति भनक्तु प्रातिकूल्येन भग्नान् आयुधग्रहणासमर्थान् करोतु । ⌛भञ्जो आमर्दने । रुधादित्वात् श्नम् प्रत्ययः⌛ । अतस्ते इषुम् बाणं प्रतिधाम् पुनर्धनुषि प्रतिहितां कर्तुं मा शकन् शक्ता न भवन्तु । ⌛शकॢ शक्तौ । माङि लुङि ऌदित्त्वात् च्लेः अङ् आदेशः⌛ ॥

सप्तमी ॥ एषां शत्रूणाम् अस्त्रम् आयुधजातम् आदित्यः सूर्यो वि नाशयतु सामर्थ्यकुण्ठनेन विनष्टं करोतु । तथा चन्द्रमाः सोमः अगतस्य अप्राप्तस्य [3]आजिगमिषतः शत्रोः पन्थाम् पन्थानम् अस्मत्प्राप्त्युपायभूतं मार्गं युताम् ततः पृथक्कुरुताम् । तादृशं मार्गं शत्रुर्न पश्यत्वित्यर्थः । ⌛यु मिश्रणामिश्रणयोः । अस्मात् लोटि अदादित्वात् शपो लुक्⌛ ॥

अष्टमी ॥

यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥ १७ ॥

यदि । प्रऽईयुः । देवऽपुराः । ब्रह्म । वर्माणि । चक्रिरे ।
तनूऽपानम् । परिऽपानम् । कृण्वानाः । यत् । उपऽऊचिरे । सर्वम् ।
तत् । अरसम् । कृधि ॥ १७ ॥

---

१ B नाशयति. We with A B[h] C D E K K[m] R S[m] V Cs. २ J अचतु ।. We with P P[2] Cp. ३ P प्रति । धाम् ।. We with P[2] J Cp.

---

1 S′ आचतु, though the text in S′ has °ग्राण्यांचतु. 2 S′ °वादेन. 3 S′ om. आ°.

यदि प्रेयुरित्येका पूर्वम् [५. ८. ६] आम्नाता । सा तत्रैव व्याख्याता ॥

नवमी ॥

क्रव्यादा[1]नुवर्तयन् मृत्युना च पुरोहितम् ।
त्रिषंधे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥ १८ ॥
क्रव्यऽअदा । अनुऽवर्तयन् । मृत्युना । च । पुरःऽहितम् ।
त्रिऽसंधे । प्र । इहि । सेनया । जय । अमित्रान् । प्र । पद्यस्व ॥ १८ ॥

[हे त्रिषंधे एतत्संज्ञक देव] पुरोहितम् पुरस्तात् स्थितं शत्रुं क्रव्यादा । क्रव्यम् आममांसम् अत्ति भक्षयतीति क्रव्यात् । तेन अनुवर्तयन् अनुगमयन् । मृत्युना मारकेण देवेन [च] अनुगमयन् । सेनया आत्मीयया प्रेहि प्रगच्छ । गत्वा च अमित्रान् शत्रून् जय तदर्थं प्र पद्यस्व शत्रुमध्यं प्रविश । ॥ पद गतौ । दिवादित्वात् श्यन् प्रत्ययः ॥ ॥

दशमी ॥

त्रिषंधे तमसा त्वममित्रान् परि वारय ।
पृषदाज्यप्र[2]णुत्तानां मामीषां मोचि कश्चन ॥ १९ ॥
त्रिऽसंधे । तमसा । त्वम् । अमित्रान् । परि । वारय ।
पृषदाज्यऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । कः । चन ॥ १९ ॥

हे त्रिषंधे एतत्संज्ञक देव त्वं तमसा मायामयेन अन्धकारेण अमित्रान् शत्रून् परि वारय परिवृतान् परिवेष्टितान् कुरु । पृषदाज्यप्रणुत्तानाम् दधिमिश्रम् आज्यं पृषदाज्यम् । तद् अस्मिन् कर्मणि होम्यत्वेन विहितम् । तेन हूयमानेन प्रणुत्तानां प्रकर्षेण क्षिप्तानाम् अमीषां शत्रूणां मध्ये कश्चन एकोऽपि मा मोचि मुक्तो मा भूत् । सर्वांस्तमसा प्रावृत्य मारयेत्यर्थः ॥

एकादशी ॥

शितिपदी सं पतत्वमित्राणाममूः सिचः[3] ।

---

१ B क्रव्यादंनु°. २ B पृषदाज्यं. We with A C D K K^m B^h E R S^m V Cs. ३ K V शुचः. We with A B B^h C D E K^m R S^m P P^2 J Cp Cs.

मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥ २० ॥ (२९)

शितिऽपदी । सम् । पततु । अमित्राणाम् । अमूः । सिचः ।

मुह्यन्तु । अद्य । अमूः । सेनाः । अमित्राणाम् । निऽअर्बुदे ॥ २० ॥

शितिः श्वेतवर्णः पादे यस्याः सा शितिपदी गौः । सा परसेनामध्ये विसृज्यमाना अमित्राणां शत्रूणां शुचः शोचमाना अस्मदायुधैर्निपीड्यमाना अमूः सेनाः सं पततु संगच्छतु । हे न्यर्बुदे एतत्संज्ञक सर्प अमित्राणाम् शत्रूणाम् अमूः दूरे दृश्यमानाः सेना अद्य इदानीं युद्धसमये मुह्यन्तु मूढा भवन्तु । स्वमायावशेन तासा मोहम् उत्पादयेत्यर्थः ॥

[इति] पञ्चमेनुवाके पञ्चमं सूक्तम् ॥

"मूढा अमित्रा न्यर्बुदे" इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ॥

तत्र प्रथमा ॥

मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।

अनया जहि सेनया ॥ २१ ॥

मूढाः । अमित्राः । निऽअर्बुदे । जहि । एषाम् । वरम्ऽवरम् ।

अनया । जहि । सेनया ॥ २१ ॥

हे न्यर्बुदे एतत्संज्ञक देव त्वम् अमित्रान् शत्रून् मूढाः त्वदीयया मायया मूढान् संजातमोहान् कर्तव्याकर्तव्यविभागज्ञानशून्यान् कुरु । एषां शत्रूणां मध्ये वरंवरम् श्रेष्ठं[श्रेष्ठं] जहि मारय । तथा अनया अस्मदीयया सेनया तान् जहि । त्वत्प्रसादाद् अस्मदीयापि सेना जयं लभताम् इत्यर्थः ॥

द्वितीया ॥

यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।

ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥ २२ ॥

---

१ KV शुचः ।. We with PP²JCp. २ BCDERS^m Cs यश्चाय्मनि. ३ BCDE RS^m °रय्मना°. K °रश्मना°. We with AB^h K^m V.

---

1 S' मूढा त्वदी°.

यः । च । कवची । यः । च । अकवचः । अमित्रः । यः । च । अज्मनि ।
ज्याऽपाशैः । कवचऽपाशैः । अज्मना । अभिऽहतः । शयाम् ॥ २२ ॥

यः शत्रुः कवची कवचवान् तनुत्रेणावृतशरीरः यश्च शत्रुः अकवचः कवचरहितः अनावृतशरीरः यश्च अमित्रः शत्रुः [अज्मनि] अजति गच्छत्यनेनेति अज्म रथादि यानम् तत्र वर्तते स सर्वः शत्रुः ज्यापाशैः स्वस्वधनुर्गतैर्मौर्वीपाशैः कवचपाशैः वर्मबन्धनपाशैः अज्मना रथादिना तत्रत्यैः पाशैश्च अभिहितः बद्धः शयाम् शेताम् । "लोपस्त आत्मनेपदेषु" इति तलोपः । अयम् अर्थः । यद्यत् स्वरक्षणाय धनुःकवचादिकम् आबध्यते तदेव तस्य गतिप्रतिबन्धकं भवत्विति ॥

तृतीया ॥

ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।
सर्वांस्ताँ अर्बुदे हतांछ्वानोऽदन्तु भूम्याम् ॥ २३ ॥

ये । वर्मिणः । ये । अवर्माणः । अमित्राः । ये । च । वर्मिणः ।
सर्वान् । तान् । अर्बुदे । हतान् । श्वानः । अदन्तु । भूम्याम् ॥ २३ ॥

उक्त एवार्थो विव्रियते । ये शत्रवो वर्मिणः वर्मणा शस्त्रवारककवचेन युक्ताः ये अवर्माणः वर्मरहिताः ये च [अमित्राः] शत्रवो वर्मिणः वर्म कवचव्यतिरिक्तं शस्त्रनिवारकम् तद्युक्ताः । तदाच्छन्ना इत्यर्थः । हे अर्बुदे तान् सर्वान् त्वया हतान् मारितान् भूम्याम् पृथिव्यां निपतितान् श्वानः श्वसृगालाद्याः श्वापदाः अदन्तु भक्षयन्तु ॥

चतुर्थी ॥

ये रथिनो ये अरथा असादा ये च सादिनः ।
सर्वानदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥ २४ ॥

---

१ P P̊ J Cp अय्मनि । २ P P̊ J Cp अय्मना । ३ B Cs सर्वास्तां. ४ B सर्वाददन्तु. K C सर्वानन्दन्तु. V सर्वान्रदन्तु. We with A B̊ D E K̊ R S̊ V Cs.

---

1 S′ अन्मति. 2 S′ यापाशैः । लोपः । लोपः for ज्यापाशैः. Did Sâyaṇa mean यापाशैः । जकारलोपः? His text too in S′ is यापाशैः.

ये । र॒थिनः॑ । ये । अ॒र॒थाः । अ॒सा॒दाः । ये । च॒ । सा॒दिनः॑ ।
सर्वा॑न् । अ॒द॒न्तु॒ । तान् । ह॒तान् । गृध्राः॑ । श्ये॒नाः । प॒त॒त्रिणः॑ ॥ २४ ॥

ये शत्रवो रथिनः रथारूढाः ये च अरथाः रथरहिताः ये च असादाः अश्वादियानरहिताः पदातयः ये च सादिनः अश्वारूढाः[1] हे अर्बुदे त्वत्प्रसादेन अस्माभिर्हतान् मारितान् तान् सर्वान् शत्रून् गृध्रादयः पक्षिणो रदन्तु विलिखन्तु । नखैर्मुखेन विलिख्य भक्षयन्त्वित्यर्थः । ✱ रद विलेखने इति धातुः ✱ ॥

पञ्चमी ॥

स॒ह॒स्र॑कुणपा शे॑ता॒मामि॒त्री सेना॑ सम॒रे व॒धाना॑म् ।
विवि॑द्धा कक॒जाकृ॑ता ॥ २५ ॥

स॒ह॒स्र॑ऽकुणपा । शे॒ता॒म् । आ॒मि॒त्री । सेना॑ । स॒म्ऽअ॒रे । व॒धाना॑म् ।
वि॒ऽवि॑द्धा । क॒क॒जा॒ऽकृ॑ता ॥ २५ ॥

आमित्री अमित्रसंबन्धिनी शात्रवी सेना अस्मदीयां सेनां[2] प्राप्य वधानाम् हननसाधनानाम् आयुधानां समरे संगमने सति विविद्धा विविधशस्त्रपातेन हता सहस्रकुणपा असंख्यातशवयुक्ता सती ककजाकृता कुत्सितजनना विलोलजनना वा कृता भवतु ॥

षष्ठी ॥

म॒र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒द॑न्तु दु॒श्चितं॑ मृदि॒तं शया॑नम् ।
य इ॒मां प्र॒तीचीमाहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥ २६ ॥

म॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णैः । अ॒द॑न्तु॑ । दुः॒ऽचित॑म् । मृदि॒तम् । शया॑नम् ।
यः । इ॒माम् । प्र॒तीची॑म् । आ॒ऽहु॑तिम् । अ॒मित्रः॑ । न॒ः । युयु॑त्सति ॥ २६ ॥

सुपर्णैः शोभनपतनैः शरैः मर्माविधम् मर्मसु स्तनमूलादिस्थानेषु वि-

१ B शते॰ and K शेमा॰ for शेता॰. We with A B^h C D E K^m R S^m P P^2 J Cp V Cs.
२ Dc ॰रदंतु corrected to ॰र्‌दंतुं. A B C D E K K^m R S^m Cs V ॰रदंतु. We with Dc P^2 Cp. ३ P J अ॒दं॒तु॒ ।. P^2 Cp अ॒दंतुं ।, which we adopt.

1 S′ अश्वरूढाः. 2 Sâyaṇa's text in S′ is सेनाम् for शेताम्.

ध्यमानम् । व्यध ताडने इत्यस्मात् मर्मशब्दोपपदात् संपदादिलक्षणः कर्मणि क्विप् । "ग्रहिज्या°" इत्यादिना संप्रसारणम् । "नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ" इति पूर्वपदस्य दीर्घः । मर्मव्यधनादेव रोरुवतम् अत्यर्थं क्रोशन्तं दुश्चितम् दुःखैः पूरितं मृदितम् चूर्णीकृतम् अत एव भूमौ शयानम् एवंभूतं शत्रुम् अदन्तु श्वसृगालादयो भक्षयन्तु । यः अमित्रः शत्रुः नः अस्माकं संबन्धिनीम् इमां पृषदाज्येन हूयमानाम् आहुतिं प्रतीचीम् प्रतिमुखम् अञ्चन्तीं प्रतिनिवृत्तगतिं कर्तुं युयुत्सति योद्धुम् इच्छति । तम् एवंभूतं भक्षयन्तु इति पूर्वत्र संबन्धः ॥

सप्तमी ॥

यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।
तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषंधिना ॥ २७ ॥ (३०)

याम् । देवाः । अनुऽतिष्ठन्ति । यस्याः । न । अस्ति । विऽराधनम् ।
तया । इन्द्रः । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥ २७ ॥

यां पृषदाज्याहुतिं देवा अनुतिष्ठन्ति वज्रोत्पादनाय आचरन्ति । यस्या आहुतेर्विराधनम् विराद्धिर्मोघवीर्यता नास्ति । अप्रतिहता शक्तिर्विद्यत इत्यर्थः । तया आहुत्या उत्पादितेन त्रिसंधिना संधित्रयोपेतेन वज्रेण वृत्रहा वृत्रासुरं हतवान् इन्द्रः हन्तु अस्मदीयान् शत्रून् हिनस्तु । "सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया" [१२] इत्यनया ऋचा[1] पृषदाज्याहुतेर्वज्ररूपता[2] प्रागेवोक्ता ॥

पञ्चमेनुवाके षष्ठं सूक्तम् ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्[3] विद्यातीर्थमहेश्वरः ॥ १ ॥

श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहरमहाराजसाम्राज्यधुरंधरेण
सायणार्येण विरचिते अथर्वसंहिताभाष्ये
एकादशकाण्डः समाप्तः ॥

---

1 S′ वा for ऋचा. 2 S′ om. °हुतेर्वज्ररू°. 3 S′ वेदात् for देयात्.

पृथिवीसूक्तम् एतत् । अस्मिन् पृथिव्याः प्रभूतं निसर्गवर्णनम् । कतिचित्पौराणिकीः कथाश्चानुलक्ष्य वर्णनम् । बहुवारं च ऋषिः पृथिवीं वरान् प्रार्थयते ॥

संप्रदायानुसारेण तु सूक्तं बहुविधं विनियुज्यते । तद्यथा "सत्यं बृहत्" इत्यनुवाको वास्तोष्पत्यगणे पठितः । अस्य गणस्य विनियोगः "इहैव ध्रुवाम्" [३. १२] इति सूक्ते द्रष्टव्यः ॥

तथा आग्रहायणीकर्मणि रात्रौ अभ्यातानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याः । ततः अनेनानुवाकेन अग्नेः पश्चाद् गर्ते दर्भान् आस्तीर्य एकं चरुं सकृत् सर्वहुतं जुहोति । द्वितीयं चरुम् अनेनानुवाकेन संपात्याभिमन्त्र्य अश्नाति । तृतीयं चरुं "सत्यं बृहत्" इति आद्याभिः सप्तभिर्ऋग्भिः "भूमे मातः" [६३] इत्यष्टम्या ऋचा च त्रिर्जुहोति । अष्टानाम् ऋचाम् आवृत्या होमत्रयं संपादनीयम् इत्यर्थः । अग्नेः पश्चाद् दर्भेषु कशिपु तृणमयं प्रस्तरणम् आस्तीर्य "विमृग्वरीम्" [२९] इत्यनयोपविशति । "यास्ते शिवाः" [९. २. २५] इति संविशति । "यच्छयानः" [३४] इति पर्यावर्तते । "सत्यं बृहत्" इति नवभिः शन्तिवा [५९] इत्यृचा "उदायुषा" [३. ३१. १०, ११] इति द्वाभ्यां च प्रातरुत्तिष्ठते । "उद्वयम्" [७. ५५. ७] इति गच्छति । "उदीराणाः" [२८] इत्यृचा प्राङ् वोदङ् वा बाह्यतो गच्छति । "यावत् ते" [३३] इत्यृचा भुवम् ईक्षते ॥ इत्याग्रहायणीकर्म ॥

तथा पुष्टिकामः उन्नतं स्थलम् आरुह्य "यावत् ते" [३३] इत्यृचा ईक्षते ॥

तथा अनेनानुवाकेन उदपात्रं संपात्य पुरस्ताद् अग्नेः सीरं युक्तं संप्रोक्षति ॥

तथा अनेनानुवाकेन कृषिकर्म भवति ॥ तच्च "सीरा युञ्जन्ति" इति [३. १७] सूक्ते विस्तरेणोक्तं द्रष्टव्यम् ॥

तथा पुत्रधनादिसर्वफलप्राप्त्यर्थं "यस्यां सदोहविर्धाने [३८–४०] इति तिसृभिराज्यं जुहोति ॥

तथा व्रीहियवाद्यन्नकामः "यस्यामन्नम् [४२] इत्यृचा पृथिवीम् उपतिष्ठते ॥

तथा मणिहिरण्यादिकामः "निधिं बिभ्रती [४४, ४५] इति द्वाभ्यां पृथिवीम् उपतिष्ठते ॥

तथा प्राप्यापि मणिं हिरण्यं वा आभ्यामेवोपतिष्ठते ॥

तथा पुष्टिकामो वृष्टिकाले "यस्यां कृष्णम् [५२] इत्यृचा नवोदकम् अभिमन्त्र्य आचमनं स्नानं च करोति ॥

तद् उक्तं कौशिकेन । "सत्यं बृहद् इत्याग्रहायण्याम् । पश्चाद् अग्नेर्दर्भेषु खदायां सर्वहुतम् । द्वितीयं संपातवन्तम् अश्नाति ।
"तृतीयस्यादितः सप्तभिर्भूमे मातरिति त्रिर्जुहोति । पश्चाद् अग्नेर्दर्भेषु कशिपूास्तीर्य विमृग्वरीम् इत्युपविशति । यास्ते शिवा
"इति संविशति । यच्छयान इति पर्यावर्तते । नवभिः शन्तिवेति दशम्योदायुषेत्युपोत्तिष्ठति । उद्वयम् इत्युत्क्रामति । उदी-
"राणा इति त्रीणि पदानि प्राङ् वोदङ् वा बाह्येनोपनिष्क्रम्य यावत् त इति वीक्षते । उन्नताच्च । पुरस्ताद् अग्नेः सीरं युक्तम्
"उदपात्रेण संपातवतावसिञ्चति । आयोजनानाम् अप्ययः । यस्यां सदोहविर्धाने इति जुहोति वरो म आगमिष्यतीति । यस्या-
"मन्नम् इत्युपतिष्ठते । निधिं बिभ्रतीति मणिं हिरण्यकामः । एवं विद्वान् । यस्यां कृष्णम् इति वार्षिकृतस्याचामति । शिर-
"स्यानयते" इति [कौ० ३. ७] ॥ वरो वरणीयोऽर्थो मम भवेद् इत्यर्थः ॥

तथा ग्रामपत्तनादिरक्षार्थम् अनेनानुवाकेन चतुरः पुरोडाशान् अश्मोत्तरान् कृत्वा ग्रामादिकोणेषु निखनति ॥

तथा ग्रामपत्तनादिरक्षार्थम् अनेनानुवाकेन एकैकस्य पुरोडाशस्य पाषाणम् उपरि कृत्वा उभयान् संपातवतः कृत्वा ग्रामादिकोणेषु निखनति । सर्वत्र प्रतिद्रव्यं सूक्तावृत्तिः ॥

तथा अग्नेरायतनस्य असंतापयुक्ते देशे शयानः एतम् अनुवाकं जपति । सर्वत्र कर्मणां विकल्पः ॥

तद् उक्तं कौशिकसूत्रे । "भौमस्य दृतिकर्माणि । पुरोडाशान् अश्मोत्तरान् अन्तः स्रक्तिषु निदधाति । उभयान्त्संपातवतः । सभाभागधानेषु च । असंतापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति" इति [कौ० ५. २] ॥

तथा भूमिचलने अस्यानुवाकस्य होमे विनियोगः । "अथ यत्रैतद् भूमिचलो भवति" इत्युपक्रम्योक्तं कौशिकेन । "सत्यं बृहद् इत्येतेनानुवाकेन जुहुयात् सा तत्र प्रायश्चित्तिः" इति [कौ० १३.६] ॥

तथा सोमयज्ञे दीक्षितनियमेषु मूत्रपुरीषशुद्ध्यर्थं लोष्टादाने अस्य विनियोगः । तद् उक्तं वैताने । "सत्यं बृहद् इति लोष्टम् आदाय" इति [वै० ३.२] ॥

तथा "पार्थिवीं भूमिकामस्य" इति [न० क० १७] विहितायां पार्थिव्यां महाशान्तौ अस्यानुवाकस्य विनियोगः । तद् उक्तं नक्षत्रकल्पे । "सत्यं बृहद् इत्यनुवाकः पार्थिव्याम्" इति [न० क० १८] ॥

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥ १ ॥

सत्यम् । बृहत् । ऋतम् । उग्रम् । दीक्षा । तपः । ब्रह्म । यज्ञः । पृथिवीम् । धारयन्ति ।
सा । नः । भूतस्य । भव्यस्य । पत्नी । उरुम् । लोकम् । पृथिवी । नः । कृणोतु ॥ १ ॥

असंबाधं बध्यतो[1] मानवानां यस्या उद्वतः प्रवतः समं बहु ।
नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥ २ ॥

असम्ऽबाधम् । मध्यतः । मानवानाम् । यस्याः । उत्ऽवतः । प्रऽवतः । समम् । बहु ।
नानाऽवीर्याः । ओषधीः । या । बिभर्ति । पृथिवी । नः । प्रथताम् । राध्यताम् । नः ॥ २ ॥

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
यस्यामिदं जिन्वति प्राणदेजत्[2] सा नो भूमिः पूर्वपेये दधातु ॥ ३ ॥

यस्याम् । समुद्रः । उत । सिन्धुः । आपः । यस्याम् । अन्नम् । कृष्टयः । सम्ऽबभूवुः ।
यस्याम् । इदम् । जिन्वति । प्राणत् । एजत् । सा । नः । भूमिः । पूर्वऽपेये । दधातु ॥ ३ ॥

यस्याश्चतस्रः प्रदिशः पृथिव्या[3] यस्यामन्नं कृष्टयः संबभूवुः ।
या बिभर्ति बहुधा प्राणदेजत्[2] सा नो भूमिर्गोष्वप्यन्ने[4][5] दधातु ॥ ४ ॥

यस्याः । चतस्रः । प्रऽदिशः । पृथिव्याः । यस्याम् । अन्नम् । कृष्टयः । सम्ऽबभूवुः ।

१ K $\overset{m}{K}$ V Dc P $\overset{2}{P}$ J मध्यतो. A B $\overset{h}{B}$ C D R $\overset{m}{S}$ Cs Cp बध्यतो. It is probable the original reading मध्यतो was changed to बध्यतो by the proximity of the ब in असंबाधं. We allow the corrupt reading to stand in the saṁhitâ text because it appears ancient and the pada text exhibits the original reading. २ K V Dc प्राणादे°, a careless misreading doubtless due to ण ाद being taken for णा द, which was further corrected into a mistake. ३ K $\overset{m}{K}$ V Dc पृथिव्यां. ४ B $\overset{h}{B}$ K $\overset{m}{K}$ R $\overset{m}{S}$ Dc °ष्वप्य°. We with A C D V Cs. ५ A C R P $\overset{2}{P}$ J °न्ने. We with $\overset{h}{B}$ D K $\overset{m}{K}$ $\overset{m}{S}$ V Dc Cs Cp.

या । बिभर्ति । बहुऽधा । प्राणत् । एजत् । सा । नः । भूमिः । गोषु । अपि । अन्ने ।
दधातु ॥ ४ ॥

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा[1] भगं वर्चः पृथिवी नो दधातु ॥ ५ ॥

यस्याम् । पूर्वे । पूर्वऽजनाः । विऽचक्रिरे । यस्याम् । देवाः । असुरान् । अभिऽअवर्तयन् ।
गवाम् । अश्वानाम् । वयसः । च । विऽस्था । भगम् । वर्चः । पृथिवी । नः । दधातु ॥ ५ ॥

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा[2] द्रविणे नो दधातु ॥ ६ ॥

विश्वम्ऽभरा । वसुऽधानी । प्रतिऽस्था । हिरण्यऽवक्षाः । जगतः । निऽवेशनी ।
वैश्वानरम् । बिभ्रती । भूमिः । अग्निम् । इन्द्रऽऋषभा । द्रविणे । नः । दधातु ॥ ६ ॥

यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥ ७ ॥

याम् । रक्षन्ति । अस्वप्नाः । विश्वऽदानीम् । देवाः । भूमिम् । पृथिवीम् । अप्रऽमादम् ।
सा । नः । मधु । प्रियम् । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥ ७ ॥

या[3]र्णवेधि सलिलमग्र आसीद् यां मायाभिरन्वचरन् मनीषिणः ।
यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
सा नो भूमिस्त्विषिं[4] बलं राष्ट्रे दधातूत्तमे ॥ ८ ॥

या । अर्णवे । अधि । सलिलम् । अग्रे । आसीत् । याम् । मायाभिः । अनुऽअचरन् ।
मनीषिणः ।
यस्याः । हृदयम् । परमे । विऽओमन् । सत्येन । आऽवृतम् । अमृतम् । पृथिव्याः ।
सा । नः । भूमिः । त्विषिम् । बलम् । राष्ट्रे । दधातु । उत्ऽतमे ॥ ८ ॥

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥ ९ ॥

---

१ A B[h] C D Cs °ष्ठा. २ D Dc °न्द्रर्षभा. ३ A C D R Cs यार्णिवे°. We with B[h] K K[m] S[m] V Dc. ४ D °षं. Dc °षिं changed to °षि.

यस्याम् । आपः । परिऽचराः । समानीः । अहोरात्रे इति । अप्रऽमादम् । क्षरन्ति ।
सा । नः । भूमिः । भूरिऽधारा । पयः । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥ ९ ॥

यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥ १० ॥(१)

याम् । अश्विनौ । अमिमाताम् । विष्णुः । यस्याम् । विऽचक्रमे ।
इन्द्रः । याम् । चक्रे । आत्मने । अनमित्राम् । शचीऽपतिः ।
सा । नः । भूमिः । वि । सृजताम् । माता । पुत्राय । मे । पयः ॥ १० ॥ (१)

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥ ११ ॥

गिरयः । ते । पर्वताः । हिमऽवन्तः । अरण्यम् । ते । पृथिवि । स्योनम् । अस्तु ।
बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् ।
अजीतः । अहतः । अक्षतः । अधि । अस्थाम् । पृथिवीम् । अहम् ॥ ११ ॥

यत् ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।
तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः ।
पर्जन्यः पिता स उ नः पिपर्तु ॥ १२ ॥

यत् । ते । मध्यम् । पृथिवि । यत् । च । नभ्यम् । याः । ते । ऊर्जः । तन्वः । सम्ऽबभूवुः ।
तासु । नः । धेहि । अभि । नः । पवस्व । माता । भूमिः । पुत्रः । अहम् । पृथिव्याः ।
पर्जन्यः । पिता । सः । ऊं इति । नः । पिपर्तु ॥ १२ ॥

यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् ।
सा नो भूमिर्वर्धयद् वर्धमाना ॥ १३ ॥

---

१ B[h] K[m] R Cs P P[2] Cp शची°. २ All our authorities read भूमिर्वर्धयद्वर्धमाना, the *pada*-authorities dividing वर्धयत् । वर्धमाना ।. The correction already made by Rw is obviously necessary.

यस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माणः ।
यस्याम् । मीयन्ते । स्वरवः । पृथिव्याम् । ऊर्ध्वाः । शुक्राः । आऽहुत्याः । पुरस्तात् ।
सा । नः । भूमिः । वर्धयत् । वर्धमाना ॥ १३ ॥

यो नो द्वेषत् पृथिवि यः पृतन्याद् योऽभिदासान्मनसा[1] यो वधेन ।
तं नो भूमे रन्धय पूर्वकृत्वरि ॥ १४ ॥

यः । नः । द्वेषत् । पृथिवि । यः । पृतन्यात् । यः । अभिऽदासात् । मनसा । यः । वधेन ।
तम् । नः । भूमे । रन्धय । पूर्वऽकृत्वरि ॥ १४ ॥

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य[2] उद्यन्त्सूर्यो र-
श्मिभिरातनोति ॥ १५ ॥

त्वत् । जाताः । त्वयि । चरन्ति । मर्त्याः । त्वम् । बिभर्षि । द्विऽपदः । त्वम् । चतुःऽपदः ।
तव । इमे । पृथिवि । पञ्च । मानवाः । येभ्यः । ज्योतिः । अमृतम् । मर्त्येभ्यः । उत्ऽयन् ।
सूर्यः । रश्मिऽभिः । आऽतनोति ॥ १५ ॥

ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥ १६ ॥

ताः । नः । प्रऽजाः । सम् । दुह्रताम् । सम्ऽअग्राः । वाचः । मधु । पृथिवि । धेहि ।
मह्यम् ॥ १६ ॥

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥ १७ ॥

विश्वऽस्वम् । मातरम् । ओषधीनाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । धर्मणा । धृताम् ।
शिवाम् । स्योनाम् । अनु । चरेम । विश्वहा ॥ १७ ॥

महत् सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।
महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।
सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥ १८ ॥

महत् । सधऽस्थम् । महती । बभूविथ । महान् । वेगः । एजथुः । वेपथुः । ते ।
महान् । त्वा । इन्द्रः । रक्षति । अप्रऽमादम् ।

---

१ B^h C E K R Cs योऽभि॰. We with A D S^m V Dc. २ A मर्ते॰.

सा । नः । भूमे । प्र । रोचय । हिरण्यस्यऽइव । सम्ऽदृशि । मा । नः । द्विक्षत । कः ।
चन ॥ १८ ॥

अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥ १९ ॥

अग्निः । भूम्याम् । ओषधीषु । अग्निम् । आपः । बिभ्रति । अग्निः । अश्मऽसु ।
अग्निः । अन्तः । पुरुषेषु । गोषु । अश्वेषु । अग्नयः ॥ १९ ॥

अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व१न्तरिक्षम् ।
अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥ २० ॥ (२)

अग्निः । दिवः । आ । तपति । अग्नेः । देवस्य । उरु । अन्तरिक्षम् ।
अग्निम् । मर्तासः । इन्धते । हव्यऽवाहम् । घृतऽप्रियम् ॥ २० ॥ (२)

अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥ २१ ॥

अग्निऽवासाः । पृथिवी । असितऽज्ञूः । त्विषिऽमन्तम् । सम्ऽशितम् । मा । कृणोतु ॥ २१ ॥

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥ २२ ॥

भूम्याम् । देवेभ्यः । ददति । यज्ञम् । हव्यम् । अरम्ऽकृतम् ।
भूम्याम् । मनुष्याः । जीवन्ति । स्वधया । अन्नेन । मर्त्याः ।
सा । नः । भूमिः । प्राणम् । आयुः । दधातु । जरत्ऽअष्टिम् । मा । पृथिवी । कृणोतु ॥ २२ ॥

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥ २३ ॥

यः । ते । गन्धः । पृथिवि । सम्ऽबभूव । यम् । बिभ्रति । ओषधयः । यम् । आपः ।
यम् । गन्धर्वाः । अप्सरसः । च । भेजिरे । तेन । मा । सुरभिम् । कृणु । मा । नः । द्वि-
क्षत । कः । चन ॥ २३ ॥

---

१ ABB^h CE ३. We with DKK^m S^m V Dc Cs. २ S^m मानुष्याः. ३ P दुदाति ।

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥ २४ ॥

यः । ते । गन्धः । पुष्करम् । आऽविवेश । यम् । सम्ऽजभ्रुः । सूर्यायाः । विऽवाहे ।
अमर्त्याः । पृथिवि । गन्धम् । अग्रे । तेन । मा । सुरभिम् । कृणु । मा । नः । द्विक्षत । कः । चन ॥ २४ ॥

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
यो अश्वेषु[१] वीरेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद् भूमे[२] तेनास्माँ[३] अपि सं सृज मा नो द्विक्षत कश्चन ॥ २५ ॥

यः । ते । गन्धः । पुरुषेषु । स्त्रीषु । पुम्ऽसु । भगः । रुचिः ।
यः । अश्वेषु । वीरेषु । यः । मृगेषु । उत । हस्तिषु ।
कन्यायाम् । वर्चः । यत् । भूमे । तेन । अस्मान् । अपि । सम् । सृज । मा । नः । द्विक्षत । कः । चन ॥ २५ ॥

शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।
तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥ २६ ॥

शिला । भूमिः । अश्मा । पांसुः । सा । भूमिः । सम्ऽधृता । धृता ।
तस्यै । हिरण्यऽवक्षसे । पृथिव्यै । अकरम् । नमः ॥ २६ ॥

यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
पृथिवीं विश्वधायसं धृतामच्छावदामसि ॥ २७ ॥

यस्याम् । वृक्षाः । वानस्पत्याः । ध्रुवाः । तिष्ठन्ति । विश्वहा ।
पृथिवीम् । विश्वऽधायसम् । धृताम् । अच्छऽआवदामसि ॥ २७ ॥

उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।

---

१ S̊ Cs अश्व्येषु. २ B̊ C D S̊ यद्भूमे. We with A E K K̊ R V Dc Cs P P̊ J Cp.
३ R E तेनास्मँ.

पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥ २८ ॥

उत्ऽईराणाः । उत । आसीनाः । तिष्ठन्तः । प्रऽक्रामन्तः ।

पत्ऽभ्याम् । दक्षिणऽसव्याभ्याम् । मा । व्यथिष्महि । भूम्याम् ॥ २८ ॥

विमृग्वरीं पृथिवीमा[1] वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।

ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥ २९ ॥

विऽमृग्वरीम् । पृथिवीम् । आ । वदामि । क्षमाम् । भूमिम् । ब्रह्मणा । ववृधानाम् ।

ऊर्जम् । पुष्टम् । बिभ्रतीम् । अन्नऽभागम् । घृतम् । त्वा । अभि । नि । सीदेम । भूमे ॥ २९ ॥

शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये[2] तं नि दध्मः ।

पवित्रेण पृथिवि मोत् पुनामि ॥ ३० ॥ (३)

शुद्धाः । नः । आपः । तन्वे । क्षरन्तु । यः । नः । सेदुः[2] । अप्रिये । तम् । नि । दध्मः ।

पवित्रेण । पृथिवि । मा[3] । उत् । पुनामि ॥ ३० ॥ (३)

यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद् याश्च पश्चात् ।

स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥ ३१ ॥

याः । ते । प्राचीः । प्रऽदिशः । याः । उदीचीः । याः । ते । भूमे । अधरात् । याः ।
च । पश्चात् ।

स्योनाः । ताः । मह्यम् । चरते । भवन्तु । मा । नि । पप्तम् । भुवने । शिश्रियाणः ॥ ३१ ॥

मा नः पश्चान्मा पुरस्तान्नुदिष्ठा[4] मोत्तरादधरादुत ।

स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥ ३२ ॥

मा । नः । पश्चात् । मा । पुरस्तात् । नुदिष्ठाः । मा । उत्तरात् । अधरात् । उत ।

स्वस्ति । भूमे । नः । भव । मा । विदन् । परिऽपन्थिनः । वरीयः । यवय । वधम् ॥ ३२ ॥

यावत् तेभि विपश्यामि भूमे सूर्येण मेदिना ।

तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥ ३३ ॥

यावत् । ते । अभि । विऽपश्यामि । भूमे । सूर्येण । मेदिना ।

तावत् । मे । चक्षुः । मा । मेष्ट[5] । उत्तराम्ऽउत्तराम् । समाम् ॥ ३३ ॥

---

१ B^h D S^m पृथिवींमा. २ K^m स्वे°. A B^h C E R P P^2 J स्ये°. We with D K S^m V Dc Cs Cp. ३ P मा । उत् ।. We with P^2 J Cp. ४ C S^m °द्विष्ठा. ५ P मेष्टाः ।.

यच्छयानः पर्यावर्ते दक्षिणं सव्यमभि[1] भूमे पार्श्वम् ।
उत्तानास्त्वा प्रतीचीं यत् पृष्टीभिरधिशेमहे ।
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥ ३४ ॥

यत् । शयानः । परिऽआवर्ते । दक्षिणम्[2] । सव्यम् । अभि । भूमे । पार्श्वम् ।
उत्तानाः । त्वा । प्रतीचीम् । यत् । पृष्टीभिः[1] । अधिऽशेमहे ।
मा । हिंसीः । तत्र । नः । भूमे । सर्वस्य । प्रतिऽशीवरि ॥ ३४ ॥

यत् ते भूमे विखनामि[3] क्षिप्रं तदपि रोहतु ।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम्[4] ॥ ३५ ॥

यत् । ते । भूमे । विऽखनामि । क्षिप्रम् । तत् । अपि । रोहतु ।
मा । ते । मर्म । विऽमृग्वरि[5] । मा । ते । हृदयम् । अर्पिपम् ॥ ३५ ॥

ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।
ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥ ३६ ॥

ग्रीष्मः । ते । भूमे । वर्षाणि । शरत्[6] । हेमन्तः । शिशिरः । वसन्तः ।
ऋतवः । ते । विऽहिताः । हायनीः । अहोरात्रे इति । पृथिवि । नः । दुहाताम् ॥ ३६ ॥

याप सर्पं विजमाना विमृग्वरी यस्यामासन्नग्नयो ये अप्स्व[7]न्तः ।
परा दस्यून् ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रम् ।
शक्राय दध्रे वृषभाय वृष्णे ॥ ३७ ॥

या । अप । सर्पम् । विजमाना । विऽमृग्वरी । यस्याम् । आसन् । अग्नयः । ये । अप्ऽसु । अन्तः ।
परा । दस्यून् । ददती । देवऽपीयून् । इन्द्रम् । वृणाना । पृथिवी । न । वृत्रम् ।
शक्राय । दध्रे । वृषभाय । वृष्णे ॥ ३७ ॥

यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः ।
युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥ ३८ ॥

---

१ K K^m S^m V Dc Cs P J Cp °ष्ठी°. We with A B^h C D E R P^2. २ P दक्षिणाम् ।. ३ A B^h D E विषनामि. ४ K K^m V Dc हृदयमर्पितम्. ५ P विमृग्वरि ।. ६ P शतम् ।. ७ A B^h C D E R S^m Cs ३. We with K K^m V Dc.

यस्याम् । सदोहविर्धाने इति सदःऽहविर्धाने । यूपः । यस्याम् । निऽमीयते ।
ब्रह्माणः । यस्याम् । अर्चन्ति । ऋक्ऽभिः । साम्ना । यजुःऽविदः ।
युज्यन्ते । यस्याम् । ऋत्विजः । सोमम् । इन्द्राय । पातवे ॥ ३८ ॥

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥ ३९ ॥

यस्याम् । पूर्वे । भूतऽकृतः । ऋषयः । गाः । उत्[1] । आनृचुः ।
सप्त । सत्रेण । वेधसः । यज्ञेन । तपसा । सह ॥ ३९ ॥

सा नो भूमिरा दिशतु यद्धनं कामयामहे ।
भगो अनुप्रयुङ्क्तामिन्द्र[2] एतु पुरोगवः ॥ ४० ॥ (४)

सा । नः । भूमिः । आ । दिशतु । यत् । धनम् । कामयामहे ।
भगः । अनुऽप्रयुङ्क्ताम्[2] । इन्द्रः । एतु । पुरःऽगवः ॥ ४० ॥ (४)

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।
सा नो भूमिः प्र णुदतां सपत्नानसपत्नं मा पृथिवी कृणोतु ॥ ४१ ॥

यस्याम् । गायन्ति । नृत्यन्ति । भूम्याम् । मर्त्याः । विऽऐलबाः[3] ।
युध्यन्ते । यस्याम् । आऽक्रन्दः । यस्याम् । वदति । दुन्दुभिः ।
सा । नः । भूमिः । प्र । नुदताम् । सऽपत्नान् । असपत्नम् । मा । पृथिवी । कृणोतु ॥ ४१ ॥

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥ ४२ ॥

यस्याम् । अन्नम् । व्रीहिऽयवौ । यस्याः । इमाः । पञ्च । कृष्टयः ।
भूम्यै । पर्जन्यऽपत्न्यै । नमः । अस्तु । वर्षऽमेदसे ॥ ४२ ॥

यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।

---

१ So all our authorities without exception. The reading though ungrammatical (see Pâṇ. VIII. 1. 71) is universal and ancient, due probably to a mistaken notion that आनृचुः contains the upasarga आ. See, however, XIX. ६. ५ = *Rig.* X. ९०. ११, where the pada-text would appear to be incorrect. २ B^h R P P^2 °युंक्ता°. ३ P विऽएलबाः ।.

प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥ ४३ ॥

यस्याः । पुरः । देवऽकृताः । क्षेत्रे । यस्याः । विऽकुर्वते ।
प्रजाऽपतिः । पृथिवीम् । विश्वऽगर्भाम् । आशाम्ऽआशाम् । रण्याम् । नः । कृणोतु ॥ ४३ ॥

निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
वसूनि नो वसुदा रासमाना देवी दधातु[1] सुमनस्यमाना ॥ ४४ ॥

निऽधिम् । बिभ्रती । बहुऽधा । गुहा । वसु । मणिम् । हिरण्यम् । पृथिवी । ददातु । मे ।
वसूनि । नः । वसुऽदाः । रासमाना । देवी । दधातु । सुऽमनस्यमाना ॥ ४४ ॥

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती[2] ॥ ४५ ॥

जनम् । बिभ्रती । बहुऽधा । विऽवाचसम् । नानाऽधर्माणम् । पृथिवी । यथाऽओकसम् ।
सहस्रम् । धाराः । द्रविणस्य । मे । दुहाम् । ध्रुवाऽइव । धेनुः । अनपऽस्फुरन्ती ॥ ४५ ॥

यस्ते सर्पो वृश्चिकस्तृष्टदंशमा हेमन्तजब्धो भृमलो गुहा शये[3] ।
क्रिमिर्जिन्वत् पृथिवि यद्यदेजति प्रावृषि[4] तन्नः सर्पन्मोप सृपद् यच्छिवं तेन नो मृड ॥ ४६ ॥

यः । ते । सर्पः । वृश्चिकः । तृष्टऽदंशमा । हेमन्तऽजब्धः । भृमलः । गुहा । शये ।
क्रिमिः । जिन्वत् । पृथिवि । यत्ऽयत् । एजति । प्रावृषि । तत् । नः । सर्पत् । मा । उप । सृपत् । यत् । शिवम् । तेन । नः । मृड ॥ ४६ ॥

ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च[5] यातवे ।
यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥ ४७ ॥

ये । ते । पन्थानः । बहवः । जनऽअयनाः । रथस्य । वर्त्म । अनसः । च । यातवे ।
यैः । सम्ऽचरन्ति । उभये । भद्रऽपापाः । तम् । पन्थानम् । जयेम । अनमित्रम् । अतस्करम् । यत् । शिवम् । तेन । नः । मृड ॥ ४७ ॥

---

१ A दधातु. २ B B^h K^m °पस्पुर°. A E °पस्फर°. ३ R शये. ४ So all our authorities. See Rw. ५ B E वर्त्मानसश्च.

मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः ।
वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥ ४८ ॥

मल्वम्[1] । बिभ्रती । गुरुऽभृत् । भद्रऽपापस्य । निऽधनम् । तितिक्षुः ।
वराहेण । पृथिवी । सम्ऽविदाना । सूकराय । वि । जिहीते । मृगाय ॥ ४८ ॥

ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो[2] अप बाधयास्मत् ॥४९॥

ये । ते[3] । आरण्याः । पशवः । मृगाः । वने । हिताः । सिंहाः । व्याघ्राः । पुरुषऽअदः । चरन्ति ।
उलम् । वृकम् । पृथिवि । दुच्छुनाम् । इतः । ऋक्षीकाम्[4] । रक्षः । अप । बाधय । अ-
स्मत् ॥ ४९ ॥

ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
पिशाचान्त्सर्वा रक्षांसि तानस्मद् भूमे यावय ॥ ५० ॥ (५)

ये । गन्धर्वाः । अप्सरसः । ये । च । अरायाः । किमीदिनः ।
पिशाचान् । सर्वा[5] । रक्षांसि । तान् । अस्मत् । भूमे । यवय ॥ ५० ॥ (५)

यां द्विपादः[6] पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
वातस्य प्रवामुपवामनु वात्यर्चिः ॥ ५१ ॥

याम् । द्विऽपादः । पक्षिणः । सम्ऽपतन्ति । हंसाः । सुऽपर्णाः । शकुनाः । वयांसि[7] ।
यस्याम् । वातः । मातरिश्वा । ईयते । रजांसि । कृण्वन् । च्यवयन् । च । वृक्षान् ।
वातस्य । प्रऽवाम् । उपऽवाम् । अनु । वाति । अर्चिः ॥ ५१ ॥

यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधा-
मनि ॥ ५२ ॥

---

१ P[2] मल्वम्. We with P J Cp. २ B B[h] रक्ष्यो. K V Dc Cs Cp रक्षोप. We with A C D E K K[m] R S[m]. ३ P ते ।. ४ P P[2] °कान् ।. We with J Cp. ५ P सर्वाः ।. ६ K K[m] V Dc द्विपदः. ७ A B D E Cs °वयांश्च.

यस्याम्। कृष्णम्। अरुणम्। च। संहिते इति सम्ऽहिते। अहोरात्रे इति। विहिते इति विऽहिते। भूम्याम्। अधि।

वर्षेण। भूमिः। पृथिवी। वृता। आऽवृता। सा। नः। दधातु। भद्रया। प्रिये। धाम॑ऽनिऽधामनि॥ ५२॥

द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः।
अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः॥ ५३॥

द्यौः। च। मे। इदम्। पृथिवी। च। अन्तरिक्षम्। च। मे। व्यचः।
अग्निः। सूर्यः। आपः। मेधाम्। विश्वे। देवाः। च। सम्। ददुः॥ ५३॥

अहमस्मि सहमान उत्तरो नाम भूम्याम्।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः॥ ५४॥

अहम्। अस्मि। सहमानः। उत्तरः। नाम। भूम्याम्।
अभीषाट्। अस्मि। विश्वाषाट्। आशाम्ऽआशाम्। विऽससहिः॥ ५४॥

अदो यद् देवि प्रथमाना पुरस्ताद् देवैरुक्ता व्यसर्पो महित्वम्।
आ त्वा सुभूतमविशत् तदानीमकल्पयथाः प्रदिशश्चतस्रः॥ ५५॥

अदः। यत्। देवि। प्रथमाना। पुरस्तात्। देवैः। उक्ता। विऽअसर्पः। महिऽत्वम्।
आ। त्वा। सुऽभूतम्। अविशत्। तदानीम्। अकल्पयथाः। प्रऽदिशः। चतस्रः॥ ५५॥

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम्।
ये संग्रामाः समितयस्तेषु चारु वदेम ते॥ ५६॥

ये। ग्रामाः। यत्। अरण्यम्। याः। सभाः। अधि। भूम्याम्।
ये। सम्ऽग्रामाः। सम्ऽइतयः। तेषु। चारु। वदेम। ते॥ ५६॥

अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत।
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम्॥ ५७॥

अश्वःऽइव। रजः। दुधुवे। वि। तान्। जनान्। ये। आऽअक्षियन्। पृथिवीम्। यात्। अजायत।

---

१ P आऽवृत्ता।. २ J P[2] उक्ताः।. ३ B अधि. ४ B समिधय॰. R समित॰. All other authorities have समितय॰. P J सम्ऽइतयः।. Cp सम्ऽईतयः। changed into सम्ऽइतयः।. We with P[2].

मन्द्रा । अग्रऽइत्वरी । भुवनस्य । गोपाः । वनस्पतीनाम् । गृभिः । ओषधीनाम् ॥ ५७ ॥

यद् वदामि[1] मधुमत् तद् वदामि[2] यदीक्षे तद्[3] वनन्ति मा ।

त्विषीमानस्मि जूतिमानवान्यान् हन्मि दोधतः ॥ ५८ ॥

यत् । वदामि । मधुऽमत् । तत् । वदामि । यत् । ईक्षे । तत् । वनन्ति । मा ।

त्विषिऽमान् । अस्मि । जूतिऽमान् । अव । अन्यान् । हन्मि । दोधतः ॥ ५८ ॥

शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।

भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥ ५९ ॥

शन्तिऽवा[4] । सुरभिः । स्योना । कीलालऽऊध्नी[5] । पयस्वती ।

भूमिः । अधि । ब्रवीतु । मे । पृथिवी । पयसा । सह ॥ ५९ ॥

यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।

भुजिष्यं[6] पात्रं निहितं गुहा यदाविर्भोगे अभवन्मातृमद्भ्यः ॥ ६० ॥

याम् । अनुऽऐच्छत् । हविषा । विश्वऽकर्मा । अन्तः । अर्णवे । रजसि । प्रऽविष्टाम् ।

भुजिष्यम् । पात्रम् । निऽहितम् । गुहा । यत् । आविः । भोगे । अभवत् । मातृमत्ऽभ्यः ॥ ६० ॥

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।

यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥ ६१ ॥

त्वम् । असि । आऽवपनी । जनानाम् । अदितिः । कामऽदुघा । पप्रथाना ।

यत् । ते । ऊनम् । तत् । ते । आ । पूरयाति । प्रजाऽपतिः । प्रथमऽजाः । ऋतस्य ॥ ६१ ॥

उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।

दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥ ६२ ॥

उपऽस्थाः । ते । अनमीवाः । अयक्ष्माः । अस्मभ्यम् । सन्तु । पृथिवि । प्रऽसूताः ।

दीर्घम् । नः । आयुः । प्रतिऽबुध्यमानाः । वयम् । तुभ्यम् । बलिऽहृतः । स्याम ॥ ६२ ॥

भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।

---

१ K^{m} वदानि. २ A D E K K^{m} S^{m} V Dc Cs P P^{2} J वदानि. We with B^{h} C R Cp. ३ A R °त्तद्व°. ४ P शिंतिऽवा ।. We with P^{2} J Cp. ५ P P^{2} °उध्नी ।. We with J Cp. ६ A B B^{h} C D E K K^{m} R S^{m} Dc Cs ३. We with V.

संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥ ६३ ॥ (६)

भूमे। मातः। नि। धेहि। मा। भद्रया। सुऽप्रतिस्थितम्।

सम्ऽविदाना। दिवा। कवे। श्रियाम्। मा। धेहि। भूत्याम्॥ ६३ ॥ (६)

प्रथमेनुवाके प्रथमं सूक्तम् ॥

इति प्रथमोनुवाकः ॥

क्रव्याद् नाम योग्निस्तद्विषयं सूक्तम् एतत्। त्रयोग्नयो भवन्ति। आमात्क्रव्याद्धव्यवाह इति। आमम् अपक्वम् अत्तीति आमाद् लौकिकोग्निः "येनेदं मनुष्याः पक्त्वाश्नन्ति" इति शतपथे [१. २. १. ४]। क्रव्यं शवदाहे मांसम् अत्तीति क्रव्याद् घोरस्वरूपश्चितानिः पितृभ्यः "येन पुरुषं दहन्ति स क्रव्याद्" इति तत्रैव। हव्यं पक्वं देवयजन आहुतम् अन्नम् अत्तीति वा देवान् प्रति तदन्नं वहतीति वा समिद्धो हव्यवाट् यागयोग्योग्निः। आमात्क्रव्यादौ यागयोग्यौ न भवतः। अत्र क्रव्यादं घोरस्वरूपम् अग्निम् अनुलक्ष्य सूक्तं प्रवर्तते। न केवलं क्रव्याच्छवदाहे शवमांसम् अत्ति अपि तु घोरत्वाद् यक्ष्मादीन् बहून् रोगान् मृत्युं च बहुविधम् आवहति। तथैव नानाप्रकारको भवति। तास्ता आपदस्तांस्तान् रोगांस्तं तं च मृत्युं सूक्तकर्ता प्रार्थनया परिहारयति। अपि च क्रव्यादो यद् घोरं रूपं तेन स शत्रून् मारयत्विति प्रार्थयते। सर्वाणि पापानि क्रव्याद् अपहरत्वित्याशास्ते। तथैव क्रव्यादो नाशाय गार्हपत्यसाग्नेः प्रार्थना। क्रव्यादोग्नेर्ये पर्युपासकास्ते नाशमाप्नुवन्तीत्याह ॥

सांप्रदायिकाः क्रव्याच्छमने विनियुञ्जते। क्रव्यादं शमयिष्यन् क्रव्याच्छमनकामः कौशिकेनोक्तप्रकारेण कर्म करोति। तत् सर्वं "पित्र्यमग्निं शमयिष्यन् ज्येष्ठस्य चाविभक्तिनः" इत्यादि नवमेध्याये चतुर्थकण्डिकां यावत् प्रपञ्चितं द्रष्टव्यम् ॥

नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि।

यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ् परेहि ॥ १ ॥

नडम्। आ। रोह। न। ते। अत्र। लोकः। इदम्। सीसम्। भागऽधेयम्। ते। आ। इहि।

यः। गोषु। यक्ष्मः। पुरुषेषु। यक्ष्मः। तेन। त्वम्। साकम्। अधराङ्। परा। इहि ॥ १ ॥

अघशंसदुःशंसाभ्यां करेणानुकरेण च।

यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥ २ ॥

अघशंसऽदुःशंसाभ्याम्। करेण। अनुऽकरेण। च।

यक्ष्मम्। च। सर्वम्। तेन। इतः। मृत्युम्। च। निः। अजामसि ॥ २ ॥

निरितो मृत्युं निर्ऋतिं निररातिमजामसि।

यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद् यमु द्विष्मस्तमु ते प्र सुवामसि ॥ ३ ॥

निः। इतः। मृत्युम्। निःऽऋतिम्। निः। अरातिम्। अजामसि।

यः। नः। द्वेष्टि। तम्। अद्धि। अग्ने। अक्रव्यऽअत्। यम्। ऊं इति। द्विष्मः। तम्। ऊं इति। ते। प्र। सुवामसि ॥ ३ ॥

---

१ A B B[h] C E तमद्ध्यंग्ने. D K K[m] R S[m] V D[c] C[s] तमध्यंग्ने. P P[2] J V C[P] अधि।. The correction is obvious. See Whitney's *Index*. २ P P[2] C[P] अक्रव्युऽअत्।. We with J.

यद्यग्निः क्रव्याद् यदि वा व्याघ्र[1] इमं गोष्ठं प्रविवेशान्योकाः ।
तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदो[2]प्यग्नीन् ॥ ४ ॥

यदि । अग्निः । क्रव्यऽअत् । यदि । वा । व्याघ्रः । इमम् । गोऽस्थम् । प्रऽविवेश । अन्यऽओकाः ।

तम् । माषऽआज्यम् । कृत्वा । प्र । हिणोमि । दूरम् । सः । गच्छतु । अप्सुऽसदः । अपि । अग्नीन् ॥ ४ ॥

यत् त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।
सुकल्पमग्ने तत् त्वया पुनस्त्वोद्दीपयामसि ॥ ५ ॥

यत् । त्वा । क्रुद्धाः । प्रऽचक्रुः । मन्युना । पुरुषे । मृते ।

सुऽकल्पम् । अग्ने । तत् । त्वया । पुनः । त्वा । उत् । दीपयामसि ॥ ५ ॥

पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।
पुनस्त्वा ब्रह्मणस्पतिराधाद् दीर्घायुत्वाय शतशारदाय ॥ ६ ॥

पुनः । त्वा । आदित्याः । रुद्राः । वसवः । पुनः । ब्रह्मा । वसुऽनीतिः । अग्ने ।

पुनः । त्वा । ब्रह्मणः । पतिः । आ । अधात् । दीर्घायुऽत्वाय । शतऽशारदाय ॥ ६ ॥

यो अग्निः क्रव्यात् प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥ ७ ॥

यः । अग्निः । क्रव्यऽअत् । प्रऽविवेश । नः । गृहम् । इमम् । पश्यन् । इतरम् । जातऽवेदसम् ।

तम् । हरामि । पितृऽयज्ञाय । दूरम् । सः । घर्मम् । इन्धाम् । परमे । सधऽस्थे ॥ ७ ॥

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥ ८ ॥

क्रव्यऽअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमऽराज्ञः । गच्छतु । रिप्रऽवाहः ।

इह । अयम् । इतरः । जातऽवेदाः । देवः । देवेभ्यः । हव्यम् । वहतु । प्रऽजानन् ॥ ८ ॥

[3]क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।

---

१ So all our authorities. See Rw. २ B^h D E Cs °षदो°. ३ All our Mss. omit क्रव्यादम्. But it is to be understood as usual, as verses 8 and 10 begin with it. But the fact that **K V** omit it shows that the tradition of this Veda is derived from Mss. and is not strictly oral as it should always be. Though the Mss. omit repeated words the reciters do not.

नि तं शास्ति[1] गार्हपत्येन विद्वान् पितॄणां लोके[2]पि भागो अस्तु ॥ ९ ॥

क्रव्यऽअदम् । अग्निम् । इषितः । हरामि । । जनान् । दृंहन्तम् । वज्रेण । मृत्युम् ।
नि । तम् । शास्ति । गार्हऽपत्येन । विद्वान् । पितॄणाम् । लोके । अपि । भागः । अस्तु ॥ ९ ॥

क्रव्यादमग्निं शशमानमुक्थ्यं[3] प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥ १० ॥ (७)

क्रव्यऽअदम् । अग्निम् । शशमानम् । उक्थ्यम् । प्र । हिणोमि । पथिऽभिः । पितृऽयानैः ।
मा । देवऽयानैः । पुनः । आ । गाः । अत्र । एव । एधि । पितृषु । जागृहि । त्वम् ॥ १० ॥ (७)

समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥ ११ ॥

सम् । इन्धते । सम्ऽकसुकम् । स्वस्तये । शुद्धाः । भवन्तः । शुचयः । पावकाः ।
जहाति । रिप्रम् । अति । एनः । एति । सम्ऽइद्धः । अग्निः । सुऽपुना । पुनाति ॥ ११ ॥

देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत् ।
मुच्यमानो निरेणसो[4]ऽमोगस्माँ[5] अशस्त्याः ॥ १२ ॥

देवः । अग्निः । सम्ऽकसुकः । दिवः । पृष्ठानि । आ । अरुहत् ।
मुच्यमानः । निः । एनसः । अमोक् । अस्मान् । अशस्त्याः ॥ १२ ॥

अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे[6] ।
अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्[7] ॥ १३ ॥

अस्मिन् । वयम् । सम्ऽकसुके । अग्नौ । रिप्राणि । मृज्महे ।
अभूम । यज्ञियाः । शुद्धाः । प्र । नः । आयूंषि । तारिषत् ॥ १३ ॥

संकसुको विकसुको निर्ऋथो यश्च निस्वरः[8] ।
ते ते यक्ष्मं सवेदसो दूराद् दूरमनीनशन्[9] ॥ १४ ॥

---

१ R शास्ति. २ $\overset{h}{\mathrm{B}}$ C अपि for °पि. ३ A B $\overset{h}{\mathrm{B}}$ C D E R $\overset{m}{\mathrm{S}}$ Dc Cs ३. We with K $\overset{m}{\mathrm{K}}$ V. ४ C R Dc निरेनसो. ५ R E °गस्माँ. ६ B मृग्महे. ७ A $\overset{h}{\mathrm{B}}$ C E K $\overset{m}{\mathrm{K}}$ R $\overset{2}{\mathrm{P}}$ J तार्षत्. We with D $\overset{m}{\mathrm{S}}$ V Dc Cs P Cp. ८ R E Dc Cp निःस्वरः. We with A $\overset{h}{\mathrm{B}}$ C D K $\overset{m}{\mathrm{K}}$ $\overset{m}{\mathrm{S}}$ V Cs P $\overset{2}{\mathrm{P}}$ J. ९ All our saṁhitâ authorities have °नीनशं. And so the pada authorities too except J $\overset{2}{\mathrm{P}}$ Cp which have °नीनशम् ।.

सम्ऽकसुकः । विऽकसुकः । निःऽऋथः । यः । च । निऽस्वरः ।
ते । ते । यक्ष्मम् । सऽवेदसः । दूरात् । दूरम् । अनीनशन् ॥ १४ ॥

यो नो[1] अश्वेषु वीरेषु यो नो गोष्वजाविषु ।
क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥ १५ ॥

यः । नः । अश्वेषु । वीरेषु । यः । नः । गोषु । अजऽअविषु ।
क्रव्यऽअदम् । निः । नुदामसि । यः । अग्निः । जनऽयोपनः ॥ १५ ॥

अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।
निः[2] क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥ १६ ॥

अन्येभ्यः । त्वा । पुरुषेभ्यः । गोभ्यः । अश्वेभ्यः । त्वा ।
निः । क्रव्यऽअदम् । नुदामसि । यः । अग्निः । जीवितऽयोपनः ॥ १६ ॥

यस्मिन् देवा अमृजत[3] यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह[4] ॥ १७ ॥

यस्मिन् । देवाः । अमृजत । यस्मिन् । मनुष्याः । उत ।
तस्मिन् । घृतऽस्तावः । मृष्ट्वा । आ । त्वम् । अग्ने । दिवम् । रुह[4] ॥ १७ ॥

समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि ज्योक् च सूर्यं दृशे ॥ १८ ॥

सम्ऽइद्धः । अग्ने । आऽहुत । सः । नः । मां । अभिऽअपक्रमीः ।
अत्र । एव । दीदिहि । द्यवि । ज्योक् । च । सूर्यम् । दृशे ॥ १८ ॥

सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत् ।
अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥ १९ ॥

सीसे । मृड्ढ्वम्[6] । नडे । मृड्ढ्वम्[6] । अग्नौ । सम्ऽकसुके । च । यत् ।
अथो इति । अव्याम् । रामायाम् । शीर्षक्तिम् । उपऽबर्हणे ॥ १९ ॥

सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।

---

१ B नु. २ A B D $\overset{m}{\text{S}}$ Cs निष्क्र॰. We with $\overset{h}{\text{B}}$ C E K $\overset{m}{\text{K}}$ R V Dc. ३ All our authorities अंमृजत, except J which has अमृजत । corrected into अमृंजत ।. ४ A B D K $\overset{m}{\text{K}}$ $\overset{m}{\text{S}}$ V Dc Cs रुहः. P $\overset{2}{\text{P}}$ J रुहः ।. We with $\overset{h}{\text{B}}$ C E R Cp. ५ P मा ।. ६ P मृड्ढम् ।.

अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥ २० ॥ (८)

सीसे । मलम् । सादयित्वा । शीर्षक्तिम् । उपऽबर्हणे ।
अव्याम् । असिक्न्याम् । मृष्ट्वा । शुद्धाः । भवत । यज्ञियाः ॥ २० ॥ (८)

परं मृत्यो अनु परेहि पन्थां यस्ते एष इतरो देवयानात्[1] ।
चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥ २१ ॥

परम् । मृत्यो[2] इति । अनु । परा । इहि । पन्थाम् । यः । ते । एषः । इतरः । देवऽयानात् ।
चक्षुष्मते । शृण्वते । ते । ब्रवीमि । इह । इमे । वीराः । बहवः । भवन्तु ॥ २१ ॥

इमे जीवा वि[3] मृतैराववृत्रन्नभूद् भद्रा देवहूतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥ २२ ॥

इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य ।
प्राञ्चः । अगाम । नृतये । हसाय । सुऽवीरासः । विदथम् । आ । वदेम ॥ २२ ॥

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥ २३ ॥

इमम् । जीवेभ्यः । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् ।
शतम् । जीवन्तः । शरदः । पुरूचीः । तिरः । मृत्युम् । दधताम् । पर्वतेन ॥ २३ ॥

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति[4] स्थ ।
तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥ २४ ॥

आ । रोहत । आयुः । जरसम् । वृणानाः । अनुऽपूर्वम् । यतमानाः । यति[4] । स्थ ।
तान् । वः । त्वष्टा । सुऽजनिमा । सऽजोषाः । सर्वम् । आयुः । नयतु । जीवनाय ॥ २४ ॥

यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति साकम् ।
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥ २५ ॥

यथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुऽभिः । यन्ति । साकम् ।
यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥ २५ ॥

---

१ B^h देवयानान्. २ P मृत्यो॰ ।. ३ B R विमृतै॰. ४ A D K K^m S^m V Dc Cs Cp यदि. E ॰ति changed to ॰दि. We with B^h C R P P^2 J.

अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः[1] ।
अत्रा जहीत ये असन् दुरेवा अनमीवानुत्तरेमाभि वाजान् ॥ २६ ॥
अश्मन्ऽवती । रीयते । सम् । रभध्वम् । वीरयध्वम् । प्र । तरत । सखायः ।
अत्र । जहीत । ये । असन् । दुःऽएवाः । अनमीवान् । उत् । तरेम । अभि । वाजान् ॥ २६ ॥

उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।
अत्रा जहीत ये असन्नशिवाः[2] शिवान्त्स्योनानुत्तरेमाभि वाजान् ॥२७॥
उत् । तिष्ठत । प्र । तरत । सखायः । अश्मन्ऽवती । नदी । स्यन्दते । इयम् ।
अत्र । जहीत । ये । असन् । अशिवाः । शिवान् । स्योनान् । उत् । तरेम । अभि । वाजान् ॥ २७ ॥

वैश्वदेवीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥ २८ ॥
वैश्वऽदेवीम् । वर्चसे । आ । रभध्वम् । शुद्धाः । भवन्तः । शुचयः । पावकाः ।
अतिऽक्रामन्तः । दुःऽइता । पदानि । शतम् । हिमाः । सर्वऽवीराः । मदेम ॥ २८ ॥

उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।
त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥ २९ ॥
उदीचीनैः । पथिऽभिः । वायुमत्ऽभिः । अतिऽक्रामन्तः । अवरान् । परेभिः ।
त्रिः । सप्त । कृत्वः । ऋषयः । पराऽइताः[3] । मृत्युम् । प्रति । औहन् । पदऽयोपनेन ॥ २९ ॥

मृत्योः पदं योपयन्त एत द्राघीय आयुः[4] प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थेऽथ[5] जीवासो विदथमा वदेम ॥ ३० ॥ (९)
मृत्योः । पदम् । योपयन्तः । आ । इत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ।
आसीनाः । मृत्युम् । नुदत । सधऽस्थे । अथ । जीवासः । विदथम् । आ । वदेम ॥३०॥ (९)

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ ३१ ॥
इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम् । स्पृशन्ताम् ।

---

१ A B^h R सखायः. २ D येसन्न°. ३ P P^2 °इतः।. ४ S^m D Cs आयुष्प्र°. ५ E सधस्थेथ जीवासो.

अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥ ३१ ॥

व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्य१हं कल्पयामि ।

स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥ ३२ ॥

विऽआकरोमि । हविषा । अहम् । एतौ । तौ । ब्रह्मणा । वि । अहम् । कल्पयामि ।

स्वधाम् । पितृऽभ्यः । अजराम् । कृणोमि । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥ ३२ ॥

यो नो अग्निः पितरो हृत्स्व१न्तराविवेशामृतो मर्त्येषु ।

मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥ ३३ ॥

यः । नः । अग्निः । पितरः । हृत्ऽसु । अन्तः । आऽविवेश । अमृतः । मर्त्येषु ।

मयि । अहम् । तम् । परि । गृह्णामि । देवम् । मा । सः । अस्मान् । द्विक्षत । मा । वयम् । तम् ॥ ३३ ॥

अपावृत्य गार्हपत्यात् क्रव्यादा प्रेत दक्षिणा ।

प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥ ३४ ॥

अपऽआवृत्य । गार्हऽपत्यात् । क्रव्यऽअदा । प्र । इत । दक्षिणा ।

प्रियम् । पितृऽभ्यः । आत्मने । ब्रह्मऽभ्यः । कृणुत । प्रियम् ॥ ३४ ॥

द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।

अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥ ३५ ॥

द्विभागऽधनम् । आऽदाय । प्र । क्षिणाति । अवर्त्या ।

अग्निः । पुत्रस्य । ज्येष्ठस्य । यः । क्रव्यऽअत् । अनिःऽआहितः ॥ ३५ ॥

यत् कृषते यद् वनुते यच्च वस्नेन विन्दते ।

सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥ ३६ ॥

यत् । कृषते । यत् । वनुते । यत् । च । वस्नेन । विन्दते ।

सर्वम् । मर्त्यस्य । तत् । न । अस्ति । क्रव्यऽअत् । च । इत् । अनिःऽआहितः ॥ ३६ ॥

---

१ A B $\overset{h}{B}$ C D E R $\overset{m}{S}$ Dc Cs ३ for १. We with K $\overset{m}{K}$ V. २ A $\overset{h}{B}$ K $\overset{m}{K}$ V Dc °मां सृं-जामि. ३ E पितरो. $\overset{m}{K}$ पितरो. ४ A $\overset{h}{B}$ C D E R $\overset{m}{S}$ Cs ३. We with K $\overset{m}{K}$ V Dc. ५ A मर्तेषु. ६ K V °दात्प्रेत. ७ C R Cs P वस्तेन. We with A $\overset{h}{B}$ D E K $\overset{m}{K}$ $\overset{m}{S}$ V Dc $\overset{2}{P}$ J Cp. ८ A B D Cs क्रव्याच्चे°. ९ P J V Cp अस्ति ।. We with $\overset{2}{P}$.

अयज्ञियो हृतवर्चा भवति नैनेन हविरत्तवे।
छिनत्ति कृष्या गोर्धनाद् यं क्रव्यादनुवर्तते ॥ ३७ ॥
अयज्ञियः। हृतऽवर्चाः। भवति। न। एनेन। हविः। अत्तवे।
छिनत्ति। कृष्याः। गोः। धनात्। यम्। क्रव्यऽअत्। अनुऽवर्तते ॥ ३७ ॥
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य।
क्रव्याद् यानग्निरन्तिकादनुविद्वान् वितावति ॥ ३८ ॥
मुहुः। गृध्यैः। प्र। वदति। आर्तिम्। मर्त्यः। निऽइत्य।
क्रव्यऽअत्। यान्। अग्निः। अन्तिकात्। अनुऽविद्वान्। विऽतावति ॥ ३८ ॥
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतिः।
ब्रह्मैव विद्वानेष्यो३ यः क्रव्यादं निरादधत् ॥ ३९ ॥
ग्राह्याः। गृहाः। सम्। सृज्यन्ते। स्त्रियाः। यत्। म्रियते। पतिः।
ब्रह्मा। एव। विद्वान्। एष्यः। यः। क्रव्यऽअदम्। निःऽआदधत् ॥ ३९ ॥
यद् रिप्रं शमलं चकृम यच्च दुष्कृतम्।
आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥ ४० ॥ (१०)
यत्। रिप्रम्। शमलम्। चकृम। यत्। च। दुःऽकृतम्।
आपः। मा। तस्मात्। शुम्भन्तु। अग्नेः। सम्ऽकसुकात्। च। यत् ॥ ४० ॥ (१०)
ता अधरादुदीचीराववृत्रन् प्रजानतीः पथिभिर्देवयानैः।
पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥ ४१ ॥
ताः। अधरात्। उदीचीः। आ। अववृत्रन्। प्रऽजानतीः। पथिऽभिः। देवऽयानैः।
पर्वतस्य। वृषभस्य। अधि। पृष्ठे। नवाः। चरन्ति। सरितः। पुराणीः ॥ ४१ ॥
अग्ने अक्रव्यान्निः क्रव्यादं नुदा देवयजनं वह ॥ ४२ ॥
अग्ने। अक्रव्यऽअत्। निः। क्रव्यऽअदम्। नुद। आ। देवऽयजनम्। वह ॥ ४२ ॥
इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्।

---

१ P भवति।. २ P J Cp एनेन।. ३ B ग्रहाः. ४ B̊ K १. ५ S̊ °दधात्. P J निःऽआदधत्।. ६ B B̊ C Dc दुःकृतम्. ७ A D E S̊ Cs °न्निष्क्रव्यादं. R °न्निःष्क्रव्यादं. We with B̊ C K K̊ V Dc. ८ P Cp अक्रव्यऽअत्।. We with J P̊.

व्याघ्रौ कृ[1]त्वा नानानं तं हरामि शिवापरम् ॥ ४३ ॥

इमम् । क्रव्यऽअत् । आ । विवेश । अयम् । क्रव्यऽअदम् । अनु । अगात् ।

व्याघ्रौ । कृत्वा । नानानम् । तम् । हरामि । शिवऽअपरम् ॥ ४३ ॥

अन्तर्धिर्देवानां परिधिर्मनुष्याणा-[2]

मग्निर्गार्हपत्य उभया[3]नन्तरा श्रितः ॥ ४४ ॥

अन्तःऽधिः । देवानाम् । परिऽधिः । मनुष्याणाम् ।

अग्निः । गार्हऽपत्यः । उभयान् । अन्तरा । श्रितः ॥ ४४ ॥

जीवानामायुः प्र तिर त्वमग्ने पितृणां लोकमपि गच्छन्तु ये मृताः ।

सुगार्हपत्यो वित[4]पन्नरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥ ४५ ॥

जीवानाम् । आयुः । प्र । तिर । त्वम् । अग्ने । पितृणाम् । लोकम् । अपि । गच्छन्तु । ये । मृताः ।

सुऽगार्हपत्यः । विऽतपन्[4] । अरातिम् । उषाम्ऽउषाम् । श्रेयसीम् । धेहि । अस्मै ॥ ४५ ॥

सर्वानग्ने सहमानः सपत्नानैषामूर्जं रयिमस्मासु धेहि ॥ ४६ ॥

सर्वान् । अग्ने । सहमानः । सऽपत्नान् । आ । एषाम् । ऊर्जम् । रयिम् । अस्मासु । धेहि ॥ ४६ ॥

इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद् दुरितादवद्यात् ।

तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥ ४७ ॥

इमम् । इन्द्रम् । वह्निम् । पप्रिम्[5] । अनुऽआरभध्वम् । सः । वः । निः । वक्षत् । दुःऽइतात् । अवद्यात् ।

तेन । अप । हत । शरुम् । आऽपतन्तम् । तेन । रुद्रस्य । परि । पात । अ[6]स्ताम् ॥ ४७ ॥

अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद् दुरितादवद्यात् ।

आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥ ४८ ॥

अनड्वाहम् । प्लवम्[7] । अनुऽआरभध्वम् । सः । वः । निः । वक्षत् । दुःऽइतात् । अवद्यात् ।

आ । रोहत । सवितुः । नावम् । एताम् । षट्ऽभिः । उर्वीभिः । अमतिम् । तरेम ॥ ४८ ॥

---

१ B क्रत्वा. २ The *Sarvânukramanî* and the *Panchapaṭalikâ* and our Saṁhitâ authorities do not put an *avasâna* after °नुष्याणाम्, though of course the pada authorities as usual indicate the end of a pâda by a ॥. See Rw. ३ C R उभयान°.
४ K K̈ S̈ V Dc Cs Cp विलपन्न°. We with A B C D E R P P J. ५ P प्रपिम् ।.
६ P आस्ताम् ।. ७ P प्लुलम् ।.

अहोरात्रे अन्वेषि बिभ्रत् क्षेम्यस्तिष्ठन्[1] प्रतरणः सुवीरः ।
अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥ ४९ ॥

अहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्यः । तिष्ठन् । प्रऽतरणः । सुऽवीरः ।
अनातुरान् । सुऽमनसः । तल्प । बिभ्रत् । ज्योक् । एव । नः । पुरुषऽगन्धिः । एधि ॥ ४९ ॥

ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
क्रव्याद् यानग्निरन्तिकादश्व इवानुवपते नडम् ॥ ५० ॥ (११)

ते । देवेभ्यः । आ । वृश्चन्ते । पापम् । जीवन्ति । सर्वदा ।
क्रव्यऽअत् । यान् । अग्निः । अन्तिकात् । अश्वःऽइव । अनुऽवपते । नडम् ॥ ५० ॥ (११)

येऽश्रद्धा[2] धनकाम्या[3] क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥ ५१ ॥

ये । अश्रद्धाः । धनऽकाम्या । क्रव्यऽअदा । सम्ऽआसते ।
ते । वै । अन्येषाम् । कुम्भीम् । परिऽआदधति । सर्वदा ॥ ५१ ॥

प्रेव पिपतिषति[4] मनसा मुहुरा वर्तते पुनः ।
क्रव्याद् यानग्निरन्तिकादनुविद्वान् वितावति ॥ ५२ ॥

प्रऽइव । पिपतिषति । मनसा । मुहुः । आ । वर्तते । पुनः ।
क्रव्यऽअत् । यान् । अग्निः । अन्तिकात् । अनुऽविद्वान् । विऽतावति ॥ ५२ ॥

अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।
माषाः पिष्टा[5] भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥ ५३ ॥

अविः । कृष्णा । भागऽधेयम् । पशूनाम् । सीसम् । क्रव्यऽअत् । अपि । चन्द्रम् । ते । आहुः ।
माषाः । पिष्टाः । भागऽधेयम् । ते । हव्यम् । अरण्यान्याः । गह्वरम् । सचस्व ॥ ५३ ॥

इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।
तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥ ५४ ॥

---

१ K °ष्ठंन्तप्र° (sic). २ B̊ C E K̊ R येश्रद्धा. We with A D K S̊ V Dc Cs. ३ All our Saṁhitâ authorities have °काम्यात्क्र°. V °काम्यात् । and P P̊ J Cp °काम्या । आत् ।. Only Dc originally read काम्या क्र° which we follow. Rw. have the correction in the Index. ४ K विपति°. ५ K J पिष्टा. K J पिष्टाः ।.

इषीकाम् । जरतीम् । इष्ट्वा । तिल्पिञ्जम् । दण्डनम् । नडम् ।
तम् । इन्द्रः । इध्मम् । कृत्वा । यमस्य । अग्निम् । निःऽआदधौ ॥ ५४ ॥

प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।
परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥ ५५ ॥ (१२)

प्रत्यञ्चम् । अर्कम् । प्रतिऽअर्पयित्वा । प्रऽविद्वान् । पन्थाम् । वि । हि । आऽविवेश ।
परा । अमीषाम् । असून् । दिदेश । दीर्घेण । आयुषा । सम् । इमान् । सृजामि ॥ ५५ ॥ (१२)

द्वितीयेनुवाके प्रथमं सूक्तम् ॥

इति द्वितीयोनुवाकः ॥

"पुमान् पुंसोधि तिष्ठ चर्म" इति स्वर्गौदनविषयकं सूक्तम् । ऋषिः क्वचिद् ओदनं क्वचिद् दंपती संबोधयति । पक्वस्य स्वर्गौदनस्य प्रतापं तथा तेन प्रापणीयानि फलानि चिन्तयित्वाह । स्वर्गेऽनेनौदनेन पुत्रादिभिः समागमो भविष्यतीत्यभिप्रायं दर्शयति । स्वर्गौदनात् क्रव्यादं रक्षश्च पिशाचं च परिहरति । आदित्याश्च अङ्गिरसश्च एतं क्रव्यादादिभ्यः पालयन्त्वित्याशास्ते । यः स्वर्गौदनः स षष्टिवर्षानन्तरं फलप्रदो भवतीति तथा पक्तुर्निधिपा इवेति वर्ण्यते । तं च प्राच्यादिसर्वाभ्यो दिग्भ्यः संरक्षणार्थं परिदद्मस्ता एतम् अस्मदर्थे परिरक्षन्तु स चास्मान् जरापूर्वकं मृत्युंयावद् भागधेयम् आनयत्वित्याशास्य सूक्तम् उपसंहरति ॥

सांप्रदायिका यत् सवयज्ञविधौ विनियुञ्जते सूक्तं सम्यक् तत् । तच्च "अग्नीन् आधास्यमानः सवान् वा दास्यन्" इति प्रक्रम्य "यथासवम् अन्यान् पृथग्वेति प्रकृतिः" इत्यन्ते कौशिकसूत्रे [कौ० ८. १–४] द्रष्टव्यम् ॥ अयं यः सौत्रिको विनियोगस्तेन कतिपयमन्त्राणां तात्पर्यं समीचीनम् आविर्भवतीत्यसंशयम् ॥

पुमान् पुंसोधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
यावन्तावग्रे प्रथमं संमेयथुस्तद् वां वयो यमराज्ये समानम् ॥ १ ॥

पुमान् । पुंसः । अधि । तिष्ठ । चर्म । इहि । तत्र । ह्वयस्व । यतमा । प्रिया । ते ।
यावन्तौ । अग्रे । प्रथमम् । सम्ऽएयथुः । तत् । वाम् । वयः । यमऽराज्ये । समानम् ॥ १ ॥

तावद् वां चक्षुस्तति वीर्याणि तावत् तेजस्ततिधा वाजिनानि ।
अग्निः शरीरं सचते यदैधोधा पक्वान्मिथुना सं भवाथः ॥ २ ॥

तावत् । वाम् । चक्षुः । तति । वीर्याणि । तावत् । तेजः । ततिऽधा । वाजिनानि ।
अग्निः । शरीरम् । सचते । यदा । एधः । अध । पक्वात् । मिथुना । सम् । भवाथः ॥ २ ॥

---

१ R प्रविद्वान्°. २ B °सूनिदेश. B̊ °सून्दीदेश. R °मसूनदि°. ३ Such is the accent of all our authorities except P J which have दिदेश ।. ४ B D K K̊ V Dc °मांसृजामि. ५ E समेयथु°. ६ P P̊ मिथुना ।.

समस्मिँल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
पूतौ पवित्रैरुप तद्ह्वयेथां यद्यद् रेतो अधि वां संबभूव ॥ ३ ॥

सम् । अस्मिन् । लोके । सम् । ऊं इति । देवऽयाने । सम् । स्म । सम्ऽएतम् । यमऽराज्येषु ।
पूतौ । पवित्रैः । उप । तत् । ह्वयेथाम् । यत्ऽयत् । रेतः । अधि । वाम् । सम्ऽबभूव ॥ ३ ॥

आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
तासां भजध्वममृतं यमाहुर्यमोदनं पचति वां जनित्री ॥ ४ ॥

आपः । पुत्रासः । अभि । सम् । विशध्वम् । इमम् । जीवम् । जीवऽधन्याः । सम्ऽएत्य ।
तासाम् । भजध्वम् । अमृतम् । यम् । आहुः । यम् । ओदनम् । पचति । वाम् । जनित्री ॥ ४ ॥

यं वां पिता पचति यं च माता रिप्रान्निर्मुक्त्यै शमलाच्च वाचः ।
स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥ ५ ॥

यम् । वाम् । पिता । पचति । यम् । च । माता । रिप्रात् । निःऽमुक्त्यै । शमलात् । च । वाचः ।
सः । ओदनः । शतऽधारः । स्वःऽगः । उभे इति । वि । आप । नभसी इति । महिऽत्वा ॥ ५ ॥

उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥ ६ ॥

उभे इति । नभसी इति । उभयान् । च । लोकान् । ये । यज्वनाम् । अभिऽजिताः । स्वःऽगाः ।
तेषाम् । ज्योतिष्मान् । मधुऽमान् । यः । अग्रे । तस्मिन् । पुत्रैः । जरसि । सम् । श्रयेथाम् ॥ ६ ॥

प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
यद् वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥ ७ ॥

प्राचीम्ऽप्राचीम् । प्रऽदिशम् । आ । रभेथाम् । एतम् । लोकम् । श्रत्ऽदधानाः । सचन्ते ।
यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् ।
श्रयेथाम् ॥ ७ ॥

दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत् ।
तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात् ॥ ८ ॥

---

१ A K Cs तध्वं°. K[m] तत्धं°. B[h] D तद्धं°. We with E R S[m] Dc. २ B शमलाच. ३ A तस्मिन्वां corrected to तस्मिन्वयं. B corrects तस्मिन्वो (?) into तस्मिन्वयं. D K K[m] S[m] Dc Cs Cp तस्मिन्वयं. We with B[h] C E R P P[2] J.

दक्षिणाम्[1] । दिशम् । अभि । नक्षमाणौ । परिऽआवर्तेथाम् । अभि । पात्रम् । एतत् । तस्मिन् । वाम् । यमः । पितृऽभिः । सम्ऽविदानः । पक्वाय । शर्म । बहुलम् । नि । यच्छात् ॥ ८ ॥

प्रतीचीं दिशामियमिद्[2] वरं यस्यां सोमो अधिपा मृडिता च ।
तस्यां श्रयेथां सुकृतः सचेथा[3]मधा[4] पक्वान्मिथुना सं भवाथः ॥ ९ ॥

प्रतीची । दिशाम् । इयम् । इत् । वरम् । यस्याम् । सोमः । अधिऽपाः । मृडिता । च । तस्याम् । श्रयेथाम् । सुऽकृतः । सचेथाम् । अध । पक्वात् । मिथुना । सम् । भवाथः ॥ ९ ॥

उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशामुदीची कृणवन्नो अग्रम् ।
पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥ १० ॥ (१३)

उत्तरम् । राष्ट्रम् । प्रऽजया । उत्तरऽवत् । दिशाम् । उदीची । कृणवत्[5] । नः । अग्रम् । पाङ्क्तम् । छन्दः । पुरुषः । बभूव । विश्वैः । विश्वऽअङ्गैः । सह । सम् । भवेम ॥ १० ॥ (१३)

ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।
सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥ ११ ॥

ध्रुवा । इयम् । विऽराट् । नमः । अस्तु । अस्यै । शिवा । पुत्रेभ्यः । उत । मह्यम् । अस्तु । सा । नः । देवि । अदिते । विश्वऽवारे । इर्यःऽइव । गोपाः । अभि । रक्ष । पक्वम् ॥ ११ ॥

पितेव पुत्रानभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
यमोदनं पचतो देवते इह तं[6] नस्तप उत सत्यं च वेत्तु ॥ १२ ॥

पिताऽइव । पुत्रान् । अभि । सम् । स्वजस्व । नः । शिवाः । नः । वाताः । इह । वान्तु । भूमौ । यम् । ओदनम् । पचतः । देवते इति । इह । तम् । नः । तपः । उत । सत्यम् । च । वेत्तु ॥ १२ ॥

यद्यत् कृष्णः शकुन एह गत्वा त्सरन्[7] विषक्तं बिल आससाद ।
यद्वा दास्या३र्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥ १३ ॥

यत्ऽयत् । कृष्णः । शकुनः । आ । इह । गत्वा । त्सरन्[8] । विऽसक्तम् । बिले । आऽससाद ।

---

१ P दक्षिणम् ।. We with $\overset{2}{\text{P}}$ J Cp. २ B changes °मध्व° to °मिध्व°. ३ D सचेता°. ४ B °मथा. ५ P कृण्वत् ।. ६ $\overset{m}{\text{S}}$ D Cs तन्न° for तं न°. ७ $\overset{h}{\text{B}}$ C P Cp सरन् for त्सरन्. We with A D E K $\overset{m}{\text{K}}$ R $\overset{m}{\text{S}}$ V Dc Cs $\overset{2}{\text{P}}$ J. ८ $\overset{2}{\text{P}}$ त्सरम् ।.

यत् । वा । दासी । आर्द्रऽहस्ता । सम्ऽअङ्क्ते[1] । उलूखलम् । मुसलम् । शुम्भत । आपः ॥ १३ ॥

अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥१४॥

अयम् । ग्रावा । पृथुऽबुध्नः । वयःऽधाः । पूतः । पवित्रैः । अप । हन्तु । रक्षः ।
आ । रोह । चर्म । महि । शर्म । यच्छ । मा । दंपती इति दम्ऽपती । पौत्रम् । अघम् ।
नि । गाताम् ॥ १४ ॥

वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचाँ[2] अपबाधमानः ।
स उच्छ्रयातै प्र वदाति वाचं तेन लोकाँ[3] अभि सर्वान् जयेम ॥ १५ ॥

वनस्पतिः । सह । देवैः । नः । आ । अगन् । रक्षः । पिशाचान् । अपऽबाधमानः ।
सः । उत् । श्रयातै । प्र । वदाति[4] । वाचम् । तेन । लोकान् । अभि । सर्वान् । जयेम ॥ १५ ॥

सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ[5] उत यश्चकर्श ।
त्रयस्त्रिंशद् देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥ १६ ॥

सप्त । मेधान् । पशवः । परि । अगृह्णन् । यः । एषाम् । ज्योतिष्मान् । उत । यः । चकर्श ।
त्रयःऽत्रिंशत् । देवताः । तान् । सचन्ते । सः । नः । स्वःऽगम् । अभि । नेष । लोकम् ॥ १६ ॥

स्वर्गं लोकमभि नो नयासि[6] सं जायया सह पुत्रैः स्याम ।
गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन्निर्ऋतिर्मो अरातिः ॥ १७ ॥

स्वःऽगम् । लोकम् । अभि । नः । नयासि । सम् । जायया । सह । पुत्रैः । स्याम ।
गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । नः । तारीत् । निःऽऋतिः । मो
इति । अरातिः ॥ १७ ॥

ग्राहिं पाप्मानमति ताँ[7] अयाम तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्[8]मा तण्डुलं वि शरीर्[9]देवयन्तम् ॥ १८ ॥

ग्राहिम् । पाप्मानम् । अति । तान् । अयाम । तमः । वि । अस्य । प्र । वदासि । वल्गु ।
वानस्पत्यः । उत्ऽयतः । मा । जिहिंसीः । मा । तण्डुलम्[10] । वि । शरीः । देवऽयन्तम् ॥ १८ ॥

---

१ P सम्ऽअक्ते ।. २ E R पिशाचँ. ३ E लोकँ. ४ P वदति ।. We with $\overset{2}{P}$ J Cp.
५ E R ज्योतिष्मँ. ६ R जयासि. ७ E R तँ. ८ $\overset{h}{B}$ D K J जहिंसी°. A C K $\overset{m}{K}$ V Dc Cs P $\overset{2}{P}$ जिहिं°. We with E R $\overset{m}{S}$. ९ $\overset{h}{B}$ C शरै°. १० P तन्दुलम् ।.

विश्वव्यंचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्।
वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावानप तद् विनक्तु ॥ १९ ॥
विश्वऽव्यंचाः। घृतऽपृष्ठः। भविष्यन्। सऽयोनिः। लोकम्। उप। याहि। एतम्।
वर्षऽवृद्धम्। उप। यच्छ। शूर्पम्। तुषम्। पलावान्। अप। तत्। विनक्तु ॥ १९ ॥
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्।
अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥ २० ॥ (१४)
त्रयः। लोकाः। सम्ऽमिताः। ब्राह्मणेन। द्यौः। एव। असौ। पृथिवी। अन्तरिक्षम्।
अंशून्। गृभीत्वा। अनुऽआरभेथाम्। आ। प्यायन्ताम्। पुनः। आ। यन्तु। शूर्पम् ॥ २० ॥ (१४)
पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या।
एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥ २१ ॥
पृथक्। रूपाणि। बहुऽधा। पशूनाम्। एकऽरूपः। भवसि। सम्। सम्ऽऋद्ध्या।
एताम्। त्वचम्। लोहिनीम्। ताम्। नुदस्व। ग्रावा। शुम्भाति। मलगःऽइव। वस्त्रा ॥ २१ ॥
पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा।
यद्यद् द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद् वपामि ॥ २२ ॥
पृथिवीम्। त्वा। पृथिव्याम्। आ। वेशयामि। तनूः। समानी। विऽकृता। ते। एषा।
यत्ऽयत्। द्युत्तम्। लिखितम्। अर्पणेन। तेन। मा। सुस्रोः। ब्रह्मणा। अपि। तत्।
वपामि ॥ २२ ॥
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या।
उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥ २३ ॥
जनित्रीऽइव। प्रति। हर्यासि। सूनुम्। सम्। त्वा। दधामि। पृथिवीम्। पृथिव्या।
उखा। कुम्भी। वेद्याम्। मा। व्यथिष्ठाः। यज्ञऽआयुधैः। आज्येन। अतिऽसक्ता ॥ २३ ॥
अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान्।

---

१ K °कउप. D °कमप. २ K °नपिषद्विनक्तु. A E R Cs P P̊ J °मपतद्वि°. We with B̊ C D K̊ S̊ V Cp. ३ A B̊ C D E K R S̊ Dc Cs °सौ पृथि°. P J असौ।. We with K̊ P̊ Cp V. ४ A C E R Dc ३ for १. We with B̊ D K S̊ V Cs. ५ A B̊ C D E K̊ R Cs °भीत्वा अन्वा°. W with K S̊ V Dc. ६ K प्यायतां. ७ P Cp मा।. ८ A K K̊ उषा.

वरुणस्त्वा दृंहाद्धरुणे प्रतीच्यां उत्तरात् त्वा सोमः सं ददातै ॥ २४ ॥

अग्निः । पचन् । रक्षतु । त्वा । पुरस्तात् । इन्द्रः । रक्षतु । दक्षिणतः । मरुत्वान् ।
वरुणः । त्वा । दृंहात् । धरुणे । प्रतीच्याः । उत्तरात् । त्वा । सोमः । सम् । ददातै ॥ २४ ॥

पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥

पूताः । पवित्रैः । पवन्ते । अभ्रात् । दिवम् । च । यन्ति । पृथिवीम् । च । लोकान् ।
ताः । जीवलाः । जीवऽधन्याः । प्रतिऽस्थाः । पात्रे । आऽसिक्ताः । परि । अग्निः । इ-न्धाम् ॥ २५ ॥

आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।
शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥ २६ ॥

आ । यन्ति । दिवः । पृथिवीम् । सचन्ते । भूम्याः । सचन्ते । अधि । अन्तरिक्षम् ।
शुद्धाः । सतीः । ताः । ऊं इति । शुम्भन्ते । एव । ताः । नः । स्वःऽगम् । अभि । लोकम् । नयन्तु ॥ २६ ॥

उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।
ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥

उतऽईव । प्रऽभ्वीः । उत । सम्ऽमितासः । उत । शुक्राः । शुचयः । च । अमृतासः ।
ताः । ओदनम् । दंपतिऽभ्याम् । प्रऽशिष्टाः । आपः । शिक्षन्तीः । पचत । सुऽनाथाः ॥ २७ ॥

संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥ २८ ॥

सम्ऽख्याताः । स्तोकाः । पृथिवीम् । सचन्ते । प्राणापानैः । सम्ऽमिताः । ओषधीभिः ।

---

१ D दधातै. २ P² पचम् ।. ३ K °रिन्धान्. ४ Such is the accent of all our authorities. ५ P शुंभं । ते ।. J शुंभम् । ते ।. P² शुंभम् । ते ।. We with Cp. ६ A प्रशिष्टा. ७ None of our authorities have प्रशिष्टा आपः शिक्षन्तीः as appears to be required. Rw. take with the Mss. आपःशिक्षन्तीः as one word. Of our authorities only Cp has आपः । शिक्षन्तीः । which is still wanting in half the truth आपः ।. Defective as it is we follow Cp. ८ K P P² J V आपःऽशिक्षन्तीः ।. We with Cp.

असंम्ऽख्याताः । आऽउप्यमा॑नाः । सुऽवर्णाः । सर्वम् । वि । आपुः । शुचयः । शुचिऽत्वम् ॥ २८ ॥

उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।
योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥ २९ ॥[1]

उत् । योधन्ति । अभि । वल्गन्ति । तप्ताः । फेनम् । अस्यन्ति । बहुलान् । च । बिन्दून् ।
योषाऽइव । दृष्ट्वा । पतिम् । ऋत्वियाय । एतैः । तण्डुलैः । भवत । सम् । आपः ॥ २९ ॥

उत्थापय सीदतो बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम् ।
अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥ ३० ॥ (१५)

उत् । स्थापय । सीदतः । बुध्ने । एनान् । अत्ऽभिः । आत्मानम् । अभि । सम् । स्पृशन्ताम् ।
अमासि । पात्रैः । उदकम् । यत् । एतत् । मिताः । तण्डुलाः । प्रऽदिशः । यदि । इमाः ॥ ३० ॥ (१५)

प्र यच्छ पर्शुं त्वरया[2] हरौषमहिंसन्त ओषधीर्दान्तु पर्वन् ।
यासां सोमः परि राज्यं[3] बभूवामन्युता नो वीरुधो भवन्तु ॥ ३१ ॥

प्र । यच्छ । पर्शुम् । त्वरय । आ । हर । ओषम् । अहिंसन्तः । ओषधीः । दान्तु । पर्वन् ।
यासाम् । सोमः । परि । राज्यम् । बभूव । अमन्युताः । नः । वीरुधः । भवन्तु ॥ ३१ ॥

नवं बर्हिरोदनाय स्तृणीत प्रियं[4] हृदश्चक्षुषो वल्ग्वस्तु ।
तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥ ३२ ॥

नवम् । बर्हिः । ओदनाय । स्तृणीत । प्रियम् । हृदः । चक्षुषः । वल्गु । अस्तु ।
तस्मिन् । देवाः । सह । दैवीः । विशन्तु । इमम् । प्र । अश्नन्तु[5] । ऋतुऽभिः । निऽसद्य ॥ ३२ ॥

---

१ All our authorities have °मृत्वियायै° (except **C** which has °मृत्वियायैस्तैस्त्,° and **K̈** which has °मृत्वियाय एतैस्त॰), the pada-authorities reading ऋत्वियाय । एतैः ।. Rw. have changed the reading to °मृत्वियायै° (ऋत्विया या एतैः &c.). The construction with या ऋत्विया सा योषेव though not incorrect appears un-Vedic, and the reading is opposed to all the Mss. and reciters, and, further, is not necessary. In all the passages which have yet been found ऋत्विय may correctly be interpreted as equivalent to 'maithuna' (See XIV. 2. 37. Ṛv. X. 183. 2. TS. 2. 5. 1. 5). २ **K** त्वर्या, who, however, says त्वरया is a *varietas lectionis*. ३ **K K̈ V Dc** परिराज्यं. We with **A B C D E R S̈ Cs P P̈ J Cp.** ४ All our authorities read प्रियां. ५ **P J** अश्नंतु ।. We with **P̈ Cp.**

वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः ।
त्वष्ट्रेव रूपं सुकृतं[1] स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥ ३३ ॥

वनस्पते । स्तीर्णम् । आ । सीद । बर्हिः । अग्निऽस्तोमैः । सम्ऽमितः । देवताभिः ।
त्वष्ट्राऽइव । रूपम् । सुऽकृतम् । स्वऽधित्या । एना । एहाः । परि । पात्रे । ददृश्राम् ॥ ३३ ॥

षष्ट्यां शरत्सु निधिपा अभीच्छात् स्वः पक्वेनाभ्यश्नवातै ।
उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥ ३४ ॥

षष्ट्याम् । शरत्ऽसु । निधिऽपाः । अभि । इच्छात् । स्वः । पक्वेन । अभि । अश्नवातै ।
उप । एनम् । जीवान्[2] । पितरः । च । पुत्राः । एतम् । स्वःऽगम् । गमय । अन्तम् ।
अग्नेः ॥ ३४ ॥

धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्[3] वासयातः पर्यग्निधानात् ॥ ३५ ॥

धर्ता । ध्रियस्व । धरुणे । पृथिव्याः । अच्युतम् । त्वा । देवताः । च्यवयन्तु ।
तम् । त्वा । दंपती इति दम्ऽपती । जीवन्तौ । जीवऽपुत्रौ । उत् । वासयातः । परि ।
अग्निऽधानात् ॥ ३५ ॥

सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।
वि गाहे[4]थामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥ ३६ ॥

सर्वान् । सम्ऽआगाः । अभिऽजित्य । लोकान् । यावन्तः । कामाः । सम् । अतीतृपः । तान् ।
वि । गाहेथाम् । आऽयवनम् । च । दर्विः । एकस्मिन् । पात्रे । अधि । उत् । हर । ए-
नम् ॥ ३६ ॥

उप स्तृणीहि प्रथय पुरस्ताद् घृतेन पात्रमभि घारयैतत् ।
वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभि[5]हिङ्कृणोत ॥ ३७ ॥

उप । स्तृणीहि । प्रथय । पुरस्तात् । घृतेन । पात्रम् । अभि । घारय । एतत् ।
वाश्राऽइव । उस्रा । तरुणम् । स्तनस्युम् । इमम् । देवासः । अभिऽहिङ्कृणोत ॥ ३७ ॥

उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।

---

१ A $\overset{m}{K}$ P J सुकृतं. We with $\overset{h}{B}$ C D E K R $\overset{m}{S}$ V Dc Cs $\overset{2}{P}$ Cp. २ P जीवान् ।. ३ R °त्रा उद्वा°. $\overset{m}{S}$ °वुद्वास°. ४ B गायेथा°. ५ A B D अभिहि°.

तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यच्छान् ॥ ३८ ॥

उप । अस्तरीः । अकरः । लोकम् । एतम् । उरुः । प्रथताम् । असमः । स्वःऽगः ।
तस्मिन् । श्रयातै । महिषः । सुऽपर्णः । देवाः । एनम् । देवताभ्यः । प्र । यच्छान् ॥ ३८ ॥

यद्यज्जाया पचति त्वत् परःपरः पतिर्वा जाये त्वत् तिरः ।
सं तत् सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥ ३९ ॥

यत्ऽयत् । जाया । पचति । त्वत् । परःऽपरः । पतिः । वा । जाये । त्वत् । तिरः ।
सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् ।
एकम् ॥ ३९ ॥

यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः ।
सर्वांस्ताँ उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ (१६)

यावन्तः । अस्याः । पृथिवीम् । सचन्ते । अस्मत् । पुत्राः । परि । ये । सम्ऽबभूवुः ।
सर्वान् । तान् । उप । पात्रे । ह्वयेथाम् । नाभिम् । जानानाः । शिशवः । सम्ऽआयान् ॥४०॥(१६)

वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीच्छात् ॥ ४१ ॥

वसोः । याः । धाराः । मधुना । प्रऽपीनाः । घृतेन । मिश्राः । अमृतस्य । नाभयः ।
सर्वाः । ताः । अव । रुन्धे । स्वःऽगः । षष्ट्याम् । शरत्ऽसु । निधिऽपाः । अभि । इ-
च्छात् ॥ ४१ ॥

निधिं निधिपा अभ्येनमिच्छादनीश्वरा अभितः सन्तु येऽन्ये ।
अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गानरुक्षत् ॥ ४२ ॥

निऽधिम् । निधिऽपाः । अभि । एनम् । इच्छात् । अनीश्वराः । अभितः । सन्तु । ये । अन्ये ।
अस्माभिः । दत्तः । निऽहितः । स्वःऽगः । त्रिऽभिः । काण्डैः । त्रीन् । स्वःऽगान् । अ-
रुक्षत् ॥ ४२ ॥

---

१ B C D K^h P P^m P^2 J यं °त् for °न्. We with A E K R S^m V Dc Cs. Cp यच्छन् ।. २ P स्वःऽगाः ।. ३ A B B^h C D E K R S^m Dc Cs P J Cp संचन्ते. We with K^m V P^2. ४ R E सर्वांस्तँ. ५ B D सर्वास्ता. ६ D K K^m S^m Cs J षष्ठ्यां. ७ K K^m V Dc °मिच्छा°. ८ K १ for ३. Cs has no kampa. ९ P °हिताः ।. १० P स्वःऽगाः ।.

अग्नी रक्षस्तपतु यद् विदेवं क्रव्यात् पिशाच इह मा प्र पास्त ।
नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥ ४३ ॥

अग्निः । रक्षः । तपतु । यत् । विऽदेवम् । क्रव्यऽअत् । पिशाचः । इह । मा । प्र । पास्त ।
नुदामः । एनम् । अप । रुध्मः । अस्मत् । आदित्याः । एनम् । अङ्गिरसः । सचन्ताम् ॥ ४३ ॥

आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥ ४४ ॥

आदित्येभ्यः । अङ्गिरःऽभ्यः । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि ।
शुद्धऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्वःऽगम् । सुऽकृतौ । अपि । इतम् ॥ ४४ ॥

इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात् परमेष्ठी समाप ।
आ सिञ्च सर्पिर्घृतवत् समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥ ४५ ॥

इदम् । प्र । आपम् । उत्ऽतमम् । काण्डम् । अस्य । यस्मात् । लोकात् । परमेऽस्थी ।
समऽआप ।
आ । सिञ्च । सर्पिः । घृतऽवत् । सम् । अङ्ग्धि । एषः । भागः । अङ्गिरसः । नः । अत्र ॥ ४५ ॥

सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
मा नो द्यूतेव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् ॥४६॥

सत्याय । च । तपसे । देवताभ्यः । निऽधिम् । शेवऽधिम् । परि । दद्मः । एतम् ।
मा । नः । द्यूते । अव । गात् । मा । सम्ऽइत्याम् । मा । स्म । अन्यस्मै । उत् । सृजत ।
पुरा । मत् ॥ ४६ ॥

अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेधि जाया ।
कौमारो लोको अजनिष्ट पुत्रोऽ३न्वारभेथां वय उत्तरावत् ॥ ४७ ॥

अहम् । पचामि । अहम् । ददामि । मम । इत् । ऊं इति । कर्मन् । करुणे । अधि । जाया ।
कौमारः । लोकः । अजनिष्ट । पुत्रः । अनुऽआरभेथाम् । वयः । उत्तरऽवत् ॥ ४७ ॥

---

१ D रुध्मो. We with A B B[h] C E K K[m] R S[m] V Dc Cs P P[2] J Cp. २ P मा ।. ३ P J रुध्मः ।. ४ B corrects पि to प. ५ P ब्रह्मणस्य ।. ६ E प्राप°. ७ B काण्डमस्य. ८ B[h] दध्म. ९ E मेत्. B[h] वत्. A D R S[m] Cs P J मत्. We with B C K K[m] V Dc P[2] Cp. १० P द्युते ।. ११ K वंदामि. १२ K[m] S १ for ३. १३ P °निष्ट ।.

न किल्बिषमत्र नाधारो अस्ति न यन्मित्रैः सममममान एति।
अनूनं पात्रं निहितं न एतत् पक्तारं पक्वः पुनरा विशाति ॥ ४८ ॥

न। किल्बिषम्। अत्र। न। आऽधारः। अस्ति। न। यत्। मित्रैः। सम्ऽअममानः। एति।
अनूनम्। पात्रम्। निऽहितम्। नः। एतत्। पक्तारम्। पक्वः। पुनः। आ। विशाति ॥ ४८ ॥

प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति।
धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥ ४९ ॥

प्रियम्। प्रियाणाम्। कृणवाम। तमः। ते। यन्तु। यतमे। द्विषन्ति।
धेनुः। अनड्वान्। वयःऽवयः। आऽयत्। एव। पौरुषेयम्। अप। मृत्युम्। नुदन्तु ॥ ४९ ॥

समग्नयो विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्।
यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥ ५० ॥ (१७)

सम्। अग्नयः। विदुः। अन्यः। अन्यम्। यः। ओषधीः। सचते। यः। च। सिन्धून्।
यावन्तः। देवाः। दिवि। आऽतपन्ति। हिरण्यम्। ज्योतिः। पचतः। बभूव ॥५०॥ (१७)

एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये।
क्षत्रेणात्मानं परि धापयाथोमोतं वासो मुखमोदनस्य ॥ ५१ ॥

एषा। त्वचाम्। पुरुषे। सम्। बभूव। अनग्नाः। सर्वे। पशवः। ये। अन्ये।
क्षत्रेण। आत्मानम्। परि। धापयाथः। अमाऽउतम्। वासः। मुखम्। ओदनस्य ॥ ५१ ॥

यदक्षेषु वदा यत् समित्यां यद्वा वदा अनृतं वित्तकाम्या।
समानं तन्तुमभि संवसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥ ५२ ॥

यत्। अक्षेषु। वदाः। यत्। सम्ऽइत्याम्। यत्। वा। वदाः। अनृतम्। वित्तऽकाम्या।
समानम्। तन्तुम्। अभि। सम्ऽवसानौ। तस्मिन्। सर्वम्। शमलम्। सादयाथः ॥ ५२ ॥

---

१ D संनममान. $\overset{h}{B}$ R सनममान. E सममान. Cs संमममान. We with A C K $\overset{m}{K}$ $\overset{m}{S}$ V Dc P $\overset{2}{P}$ J Cp. २ B $\overset{h}{B}$ Cs निहितं. ३ $\overset{2}{P}$ किल्विषम्।. ४ P कृण्वाम्।. ५ A B $\overset{h}{B}$ D E R $\overset{m}{S}$ V Cs $\overset{2}{P}$ Cp विदु°. We with C $\overset{m}{K}$ P J. Dc विदु° changed to विदु°. ६ A $\overset{m}{S}$ सचते. ७ Dc एषां corrected to एषा. ८ $\overset{m}{S}$ त्वचा. ९ R यद्दक्षेषु. १० $\overset{h}{B}$ °काम्यां. ११ B सादयेथाः.

वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥ ५३ ॥

वर्षम् । वनुष्व । अपि । गच्छ । देवान् । त्वचः । धूमम् । परि । उत् । पातयासि ।
विश्वऽव्यचाः । घृतऽपृष्ठः । भविष्यन् । सऽयोनिः । लोकम् । उप । याहि । एतम् ॥ ५३ ॥

तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मनन्यवर्णाम् ।
अपाजैत् कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥ ५४ ॥

तन्वम् । स्वःऽगः । बहुऽधा । वि । चक्रे । यथा । विदे । आत्मन् । अन्यऽवर्णाम् ।
अप । अजैत् । कृष्णाम् । रुशतीम् । पुनानः । या । लोहिनी । ताम् । ते । अग्नौ । जुहोमि ॥ ५४ ॥

प्राच्यै त्वा दिशे३ऽग्नयेधिपतयेसिताय रक्षित्र आदित्यायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्केन सह सं भवेम ॥ ५५ ॥

प्राच्यै । त्वा । दिशे । अग्नये । अधिऽपतये । असिताय । रक्षित्रे । आदित्याय । इषुऽमते ।
एतम् । परि । दद्मः । तम् । नः । गोपायत । आ । अस्माकम् । आऽएतोः ।
दिष्टम् । नः । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । नः । ददातु । अथ । पक्केन । सह । सम् । भवेम ॥ ५५ ॥

दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
एतं०।० ॥ ५६ ॥

दक्षिणायै । त्वा । दिशे । इन्द्राय । अधिऽपतये । तिरश्चिऽराजये । रक्षित्रे । यमाय । इषुऽमते ॥० ॥ ५६ ॥

प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेन्नायेषुमते ।
एतं०।० ॥ ५७ ॥

प्रतीच्यै । त्वा । दिशे । वरुणाय । अधिऽपतये । पृदाकवे । रक्षित्रे । अन्नाय । इषुऽमते ॥० ॥५७॥

---

१ B पातयामि. R P P[2] J °पातयामसि. We with A B[h] C D E K K[m] S[m] V Dc Cs Cp.
२ S[m] °निर्लोकमुप. ३ B रुषतीं.

उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेशन्या इषुमत्यै ।
एतं०।० ॥ ५८ ॥

उदीच्यै । त्वा । दिशे । सोमाय । अधिऽपतये । स्वजाय । रक्षित्रे । अशन्यै । इषुऽमत्यै ॥० ॥५८॥

ध्रुवायै त्वा दिशे विष्णवेधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इ-षुमतीभ्यः । एतं०।० ॥ ५९ ॥

ध्रुवायै । त्वा । दिशे । विष्णवे । अधिऽपतये । कल्माषऽग्रीवाय । रक्षित्रे । ओषधीभ्यः । इषुऽमतीभ्यः ॥० ॥ ५९ ॥

ऊर्ध्वायै त्वा दिशे बृहस्पतयेधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्केन सह सं भवेम ॥ ६० ॥ (१८)

ऊर्ध्वायै । त्वा । दिशे । बृहस्पतये । अधिऽपतये । श्वित्राय । रक्षित्रे । वर्षाय । इषुऽमते ।
एतम् । परि । दद्मः । तम् । नः । गोपायत । आ । अस्माकम् । आऽएतोः ।
दिष्टम् । नः । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । नः । ददातु ।
अथ । पक्केन । सह । सम् । भवेम ॥ ६० ॥ (१८)

तृतीयेनुवाके प्रथमं सूक्तम् ॥

इति तृतीयोनुवाकः ॥

वशाविषयकं सूक्तम् एतत् । वशा गौर्या गर्भं न गृह्णातीति दारिलः (कौ॰ ५.८) । वशा वन्ध्या गौरिति सायणः (ऋ॰ २.७.५) । वशा स्वभाववन्ध्या गौरिति स एव (ऋ॰ १०.९१.१४) ।

यस्य गृहे वशा जाता तस्य गृहे 'अज्ञातगदा सती' अर्थाद् अज्ञातवशात्वरूपवैकल्या सती आ वर्षत्रयाद् रक्षितव्या । तदनन्तरम् असंग्राह्या भवति । वशा गौर्देवानां विशेषेण प्रियं हविर्भवति । तस्माद्देवानामर्थे तां याचद्भ्यो ब्राह्मणेभ्यस्तत्पतिर्दद्यादेव । तथा कृते प्रजादिवृद्धिर्भवति न च कृते बह्वय आपदः संजायन्ते । तदेव आपद्व्यसनं तस्या अदत्तायाः कस्माद्गात् कीदृशं भवतीत्याह । अन्यापि कथं विपत्तिर्भवतीति च । याचद्भ्यो ब्राह्मणेभ्योऽदत्ता वशा ब्रह्मोपद्रवादि पापं जनयति । यदा वशां ब्राह्मणा याचन्ते देवा एव तद् याचन्तीति मन्तव्यम् वशा हि देवानां भागो भवति । वशा दत्ता सती सर्वान् दातुः कामान् दुग्धे । यो वशां वेहतं मन्यमानः स्वयमेव हत्वा पचेत्तस्य हानिर्भवति । वशा हि ब्राह्मणेभ्य आत्मानं दीयमानां तैश्च हता सती देवेभ्यो हवीरूपेण अर्प्यमाणाम् इच्छति । तस्माद् यदि हुतां वा अहुतां वा यो वशापतिस्तां स्वगृह एव पचते सोधःपातम् आप्य नरकं गच्छतीत्याह ॥

वशाशमनप्रकारः कौशिके [५.८,९] प्रपञ्चितः ॥

---

१ P कल्फा॰ ।.   २ K^m V Dc P^2 श्वित्रायं.

वशादानस्य प्रकारस्तु "ददामीति वशाम् उदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः" इति कौशिके [८. ७] दर्शितः ॥

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
वशां ब्रह्मभ्यो याचद्भ्यस्तत् प्रजावदपत्यवत् ॥ १ ॥

ददामि । इति । एव । ब्रूयात् । अनु । च । एनाम् । अभुत्सत ।
वशाम् । ब्रह्मऽभ्यः । याचत्ऽभ्यः । तत् । प्रजाऽवत् । अपत्यऽवत् ॥ १ ॥

प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥ २ ॥

प्रऽजया । सः । वि । क्रीणीते । पशुऽभिः । च । उप । दस्यति ।
यः । आर्षेयेभ्यः । याचत्ऽभ्यः । देवानाम् । गाम् । न । दित्सति ॥ २ ॥

कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥ ३ ॥

कूटया । अस्य । सम् । शीर्यन्ते । श्लोणया । काटम् । अर्दति ।
बण्डया । दह्यन्ते । गृहाः । काणया । दीयते । स्वम् ॥ ३ ॥

विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशायाः संविद्यं दुरदभ्ना ह्यु१च्यसे ॥ ४ ॥

विऽलोहितः । अधिऽस्थानात् । शक्नः । विन्दति । गोऽपतिम् ।
तथा । वशायाः । सम्ऽविद्यम् । दुरदभ्ना । हि । उच्यसे ॥ ४ ॥

पदोरस्या अधिष्ठानाद् विक्लिन्दुर्नाम विन्दति ।
अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति ॥ ५ ॥

पदोः । अस्याः । अधिऽस्थानात् । विऽक्लिन्दुः । नाम । विन्दति ।
अनामनात् । सम् । शीर्यन्ते । याः । मुखेन । उपऽजिघ्रति ॥ ५ ॥

यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥ ६ ॥

---

१ B °यादनु. २ A K K[m] ह्यूच्यसे. B[h] V ह्यु१च्यसे. C S[m] Cs ह्यूच्यसे. D Dc ह्यू१च्यसे. E ह्यु३च्यसे. R ह्युच्यसे. ३ B °मनान्सं. ४ B यक्ष्म.

यः । अस्याः । कर्णौ । आऽस्कुनोति । आ । सः । देवेषु । वृश्चते ।

लक्ष्म । कुर्वे । इति । मन्यते । कनीयः । कृणुते । स्वम् ॥ ६ ॥

यदस्याः कस्मै चिद् भोगाय बालान् कश्चित् प्रकृन्तति ।

ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥ ७ ॥

यत् । अस्याः । कस्मै । चित् । भोगाय । बालान् । कः । चित् । प्रऽकृन्तति ।

ततः । किशोराः । म्रियन्ते । वत्सान् । च । घातुकः । वृकः ॥ ७ ॥

यदस्या[1] गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत् ।

ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात् ॥ ८ ॥

यत् । अस्याः । गोऽपतौ । सत्याः । लोम । ध्वाङ्क्षः । अजीहिडत् ।

ततः । कुमाराः । म्रियन्ते । यक्ष्मः । विन्दति । अनामनात् ॥ ८ ॥

यदस्याः पल्पूलनं[2] शकृद्[3] दासी समस्यति ।

ततोपरूपं जायते तस्मादव्येष्यदेनसः ॥ ९ ॥

यत् । अस्याः । पल्पूलनम् । शकृत् । दासी । सम्ऽअस्यति ।

ततः । अपऽरूपम् । जायते । तस्मात् । अविऽएष्यत् । एनसः ॥ ९ ॥

जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।

तस्माद् ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥ १० ॥ (१९)

जायमाना । अभि । जायते । देवान् । सऽब्राह्मणान् । वशा ।

तस्मात् । ब्रह्मऽभ्यः । देया । एषा । तत् । आहुः । स्वस्य । गोपनम्[4] ॥ १० ॥ (१९)

य एनां वनिमायन्ति तेषां देवकृता वशा ।

ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥ ११ ॥

ये । एनाम् । वनिम् । आऽयन्ति । तेषाम् । देवऽकृता । वशा ।

ब्रह्मऽज्येयम् । तत् । अब्रुवन् । यः । एनाम्[5] । निऽप्रियायते[6] ॥ ११ ॥

य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।

---

१ B योऽस्या॰. २ K V पल्यू॰. We with Dc Cs P Cp. The other MSS. doubtful between ॰ल्यू ॰and ॰ल्पू॰. ३ R सकृ॰. ४ P P² J Cp गोऽपनम् ।. ५ J P² एनान् ।. ६ So P P² J Cp.

आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥ १२ ॥

यः । आर्षेयेभ्यः । याचत्ऽभ्यः । देवानाम् । गाम् । न । दित्सति ।

आ । सः । देवेषु । वृश्चते । ब्राह्मणानाम् । च । मन्यवे[1] ॥ १२ ॥

यो अस्य स्याद् वशाभोगो अन्यामिच्छेत तर्हि सः ।

हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति[2] ॥ १३ ॥

यः । अस्य । स्यात्[3] । वशाऽभोगः । अन्याम् । इच्छेत । तर्हि । सः ।

हिंस्ते । अदत्ता । पुरुषम् । याचिताम् । च । न । दित्सति ॥ १३ ॥

यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।

तामेतदच्छायन्ति यस्मिन् कस्मिंश्च जायते ॥ १४ ॥

यथा । शेवऽधिः । निऽहितः । ब्राह्मणानाम् । तथा । वशा ।

ताम् । एतत् । अच्छऽआयन्ति[4] । यस्मिन् । कस्मिन् । च । जायते ॥ १४ ॥

स्वमेतदच्छायन्ति यद् वशां ब्राह्मणा[5] अभि ।

यथैनानन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥ १५ ॥

स्वम्[6] । एतत् । अच्छऽआयन्ति । यत् । वशाम् । ब्राह्मणाः । अभि ।

यथा । एनान् । अन्यस्मिन् । जिनीयात् । एव । अस्याः । निऽरोधनम् ॥ १५ ॥

चरेदेवा त्रैहायणादविज्ञातगदा सती ।

वशा च विद्यान्नारद ब्राह्मणास्तर्ह्येष्याः ॥ १६ ॥

चरेत् । एव । आ । त्रैहायनात् । अविज्ञातऽगदा । सती ।

वशाम् । च । विद्यात् । नारद । ब्राह्मणाः । तर्हि । एष्याः ॥ १६ ॥

य एनामवशामाह देवानां निहितं निधिम् ।

उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥ १७ ॥

यः । एनाम् । अवशाम् । आह । देवानाम् । निऽहितम् । निऽधिम् ।

उभौ । तस्मै । भवाशर्वौ । परिऽक्रम्य । इषुम् । अस्यतः ॥ १७ ॥

---

१ P² मृत्यवे ।. We with P J Cp. २ B दित्सते. ३ P स्यात् ।. We with P² J Cp. ४ P अच्छऽयन्ति ।. We with P² J Cp. ५ A B B^h C D E R S^m Cs P J Cp ब्राह्मणा ।. We with K K^m V Dc P². ६ P स्वाम् ।.

यो अस्या ऊधो न वेदाथो अस्या स्तनानुत ।
उभयेनैवास्मै दुहे दातुं चेदश[1]कद् वशाम् ॥ १८ ॥

यः । अस्याः । ऊधः । न । वेद । अथो इति । अस्याः । स्तनान् । उत ।
उभयेन । एव । अस्मै । दुहे । दातुम् । च । इत् । अशकत् । वशाम् ॥ १८ ॥

दुरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥ १९ ॥

दुरदभ्ना । एनम् । आ । शये । याचिताम् । च । न । दित्सति ।
न । अस्मै । कामाः । सम् । ऋध्यन्ते । याम् । अदत्त्वा । चिकीर्षति ॥ १९ ॥

देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामदद[2]द्धेडं न्ये[3]ति मानुषः ॥ २० ॥ (२०)

देवाः । वशाम् । अ[4]याचन् । मुखम् । कृत्वा । ब्राह्मणम् ।
तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुषः ॥ २० ॥ (२०)

हेडं पशूनां न्येति ब्राह्मणेभ्यो[5]ऽददद् वशाम् ।
देवानां निहितं भागं मर्त्यश्चेन्निप्रियायते ॥ २१ ॥

हेडम् । पशूनाम् । नि । एति । ब्राह्मणेभ्यः । अददत् । वशाम् ।
देवानाम् । निऽहितम् । भागम् । मर्त्यः[6] । च । इत् । निऽप्रियायते ॥ २१ ॥

यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथै[7]नां देवा अब्रुवन्नेवं ह विदुषो वशा ॥ २२ ॥

यत् । अन्ये । शतम् । याचेयुः । ब्राह्मणाः । गोऽपतिम् । वशाम् ।
अथ । एनाम् । देवाः । अब्रुवन् । एवम् । ह । विदुषः । वशा ॥ २२ ॥

---

१ C °कद्वशा. २ K S̈ V °दद्धेडं. ३ B Ḃ C E K̈ न्येति for न्येति. We with A D K S̈ V Dc Cs. ४ P अयाचन् ।. ५ All our authorities except Cp have °भ्योददद्व-शाम् (P Ṗ J K V reading अददत् in the pada-pâṭha). We with Cp. Rw have already made the correction. ६ P मर्त्याः ।. ७ A C E K R S̈ Ṗ J Cp अथैतां. We with Ḃ D K̈ V Dc Cs. ८ P एताम् ।. Ṗ J Cp एताम् ।.

य एवं विदुषे[1]ऽदत्त्वाथान्येभ्यो[2] ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥ २३ ॥

यः । एवम् । विदुषे । अदत्त्वा । अथ । अन्येभ्यः । ददत् । वशाम् ।
दुःऽगा । तस्मै । अधिऽस्थाने । पृथिवी । सहऽदेवता ॥ २३ ॥

देवा वशामयाचन् यस्मिन्नग्रे अजायत ।
तामेतां विद्यान्नारदः[3] सह देवैरुदाजत ॥ २४ ॥

देवाः । वशाम् । अयाचन् । यस्मिन् । अग्रे । अजायत ।
ताम् । एताम् । विद्यात् । नारदः । सह । देवैः । उत् । आजत ॥ २४ ॥

अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥ २५ ॥

अनपत्यम् । अल्पऽपशुम् । वशा । कृणोति । पुरुषम् ।
ब्राह्मणैः । च । याचिताम्[4] । अथ । एनाम् । निऽप्रियायते ॥ २५ ॥

अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्[5]तेष्वा वृश्चतेऽददत् ॥ २६ ॥

अग्नीषोमाभ्याम् । कामाय । मित्राय । वरुणाय । च ।
तेभ्यः । याचन्ति । ब्राह्मणाः । तेषु । आ । वृश्चते । अददत् ॥ २६ ॥

यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
चरेदस्य तावद् गोषु नास्य श्रुत्वा गृहे वसेत्[6] ॥ २७ ॥

यावत् । अस्याः । गोऽपतिः । न । उपऽशृणुयात् । ऋचः । स्वयम् ।
चरेत् । अस्य । तावत् । गोषु । न । अस्य । श्रुत्वा । गृहे । वसेत्[6] ॥ २७ ॥

---

१ **A B $\overset{h}{\mathrm{B}}$ D E Cs** विदुषें°. We with **C K $\overset{m}{\mathrm{K}}$ R $\overset{m}{\mathrm{S}}$ V Dc.** २ All our Saṁhitâ authorities have °भ्योंददद्वशाम्. **P $\overset{2}{\mathrm{P}}$ J Cp** ददत् ।. **Rw** °भ्योऽददद्वशाम्. Our correction is necessary. ३ **Dc** विंद्यान्नारंदः changed to विंद्यान्नारदः. **P $\overset{2}{\mathrm{P}}$** नारदः ।. We with **A B $\overset{h}{\mathrm{B}}$ C D E K $\overset{m}{\mathrm{K}}$ R $\overset{m}{\mathrm{S}}$ Cs J Cp.** ४ **P** यातिताम् ।. ५ **R $\overset{m}{\mathrm{S}}$** °णस्तेष्वा. ६ **A $\overset{h}{\mathrm{B}}$ C E R P $\overset{2}{\mathrm{P}}$ J** वंशेत्. We with **D K $\overset{m}{\mathrm{K}}$ $\overset{m}{\mathrm{S}}$ V Dc Cs Cp.**

यो अस्या[१] ऋचं[२] उपश्रुत्याथ गोष्वचीचरत्[३] ।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति[४] हीडिताः ॥ २८ ॥
यः । अस्याः । ऋचः । उपऽश्रुत्य । अथ । गोषु । अचीचरत्[३] ।
आयुः । च । तस्य । भूतिम् । च । देवाः । वृश्चन्ति[४] । हीडिताः ॥ २८ ॥

वशा चरन्ती बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व[५] रूपाणि यदा स्थाम जिघांसति ॥ २९ ॥
वशा । चरन्ती । बहुऽधा । देवानाम् । निऽहितः । निऽधिः ।
आविः । कृणुष्व[६] । रूपाणि । यदा । स्थाम । जिघांसति ॥ २९ ॥

आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
अथो ह ब्रह्मभ्यो वशा याञ्चँयाय[७] कृणुते मनः ॥ ३० ॥ (२१)
आविः । आत्मानम् । कृणुते । यदा । स्थाम[८] । जिघांसति ।
अथो इति । ह । ब्रह्मऽभ्यः । वशा । याच्ञँयाय । कृणुते । मनः ॥ ३० ॥ (२१)

मनसा सं कल्पयति तद् देवाँ[९] अपि गच्छति ।
ततो ह ब्रह्माणो[१०] वशामुपप्रयन्ति याचितुम् ॥ ३१ ॥
मनसा । सम् । कल्पयति । तत् । देवान् । अपि । गच्छति ।
ततः । ह । ब्रह्माणः । वशाम् । उपऽप्रयन्ति । याचितुम् ॥ ३१ ॥

स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥ ३२ ॥
स्वधाऽकारेण । पितृऽभ्यः । यज्ञेन । देवताभ्यः ।
दानेन । राजन्यः । वशायाः । मातुः । हेडम् । न । गच्छति ॥ ३२ ॥

---

१ **A D $\overset{m}{\mathrm{S}}$** अस्या ३. २ **K** ऋषं. ३ All our authorities have गोष्वचीचरत्, the pada-authorities having अचीचरत् ।. **R**w's correction appears necessary. ४ **A C D R Cs P J Cp** वृश्चंति. We with **B $\overset{h}{\mathrm{B}}$ E K $\overset{m}{\mathrm{K}}$ $\overset{m}{\mathrm{S}}$ V Dc $\overset{2}{\mathrm{P}}$**. ५ **$\overset{h}{\mathrm{B}}$ E R V Dc** आविः कृणुष्व ।. We with **A C D K $\overset{m}{\mathrm{K}}$ $\overset{m}{\mathrm{S}}$ Cs**. ६ **P $\overset{2}{\mathrm{P}}$ J** कृणुते ।. We with **Cp**. ७ **B K $\overset{m}{\mathrm{K}}$** याच्यायं. **A $\overset{h}{\mathrm{B}}$ E R $\overset{2}{\mathrm{P}}$ V** याञ्च्यायं. **D Cs** याच्ञायं. **Cp** याञ्ञायं. We with **C Dc $\overset{m}{\mathrm{S}}$ P J**. ८ **P** स्थाम ।. ९ **E R** °वँ. १० **B K $\overset{m}{\mathrm{K}}$** ब्रह्मणो.

वशा माता राजन्यस्य तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद् ब्रह्मभ्यः प्रदीयते ॥ ३३ ॥

वशा । माता । राजन्यस्य । तथा । सम्ऽभूतम् । अग्रऽशः ।
तस्याः । आहुः । अनर्पणम् । यत् । ब्रह्मऽभ्यः । प्रऽदीयते ॥ ३३ ॥

यथाज्यं प्रगृहीतमालुम्पेत् स्रुचो अग्नये[1] ।
एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्[2] ॥ ३४ ॥

यथा । आज्यम् । प्रऽगृहीतम् । आऽलुम्पेत् । स्रुचः[3] । अग्नये ।
एव । ह । ब्रह्मऽभ्यः । वशाम् । अग्नये । आ । वृश्चते । अददत् ॥ ३४ ॥

पुरोडाशवत्सा सुदुघा लोकेऽस्मा[4] उप तिष्ठति ।
सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥ ३५ ॥

पुरोडाशऽवत्सा । सुऽदुघा । लोके । अस्मै । उप । तिष्ठति ।
सा । अस्मै[5] । सर्वान् । कामान् । वशा । प्रऽददुषे । दुहे ॥ ३५ ॥

सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥ ३६ ॥

सर्वान् । कामान् । यमऽराज्ये । वशा । प्रऽददुषे । दुहे ।
अथ । आहुः । नारकम्[6] । लोकम् । निऽरुन्धानस्य[7] । याचिताम् ॥ ३६ ॥

प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥ ३७ ॥

प्रऽवीयमाना । चरति । क्रुद्धा । गोऽपतये । वशा ।
वेहतम् । मा । मन्यमानः । मृत्योः । पाशेषु । बध्यताम् ॥ ३७ ॥

यो वेहतं मन्यमानोऽमा[8] च पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥ ३८ ॥

यः । वेहतम् । मन्यमानः । अमा । च । पचते । वशाम् ।
अपि । अस्य । पुत्रान् । पौत्रान् । च । याचयते । बृहस्पतिः ॥ ३८ ॥

---

१ A R प्रगृहीत॰. २ B ॰ददत्. ३ P स्रुच ।. ४ V Dc लोकें. ५ P असै ।. ६ So P $\overset{2}{P}$ J Cp. See *Chaturâdhyâyî* 4. 90. ७ P ॰रुधानस्य ।. ८ R मन्यमानो.

महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशाददुषे विषं दुहे ॥ ३९ ॥

महत् । एषा । अव । तपति । चरन्ती । गोषु । गौः । अपि ।
अथो इति । ह । गोऽपतये । वशा । अददुषे । विषम् । दुहे ॥ ३९ ॥

प्रियं पशूनां भवति यद् ब्रह्मभ्यः प्रदीयते ।
अथो वशायास्तत् प्रियं यद् देवत्रा हविः स्यात्[1] ॥ ४० ॥ (२२)

प्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्यः । प्रऽदीयते ।
अथो इति । वशायाः । तत् । प्रियम् । यत् । देवऽत्रा । हविः । स्यात् ॥ ४० ॥ (२२)

या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं[2] भीमामुदाकुरुत नारदः ॥ ४१ ॥

याः । वशाः । उत्ऽअकल्पयन् । देवाः । यज्ञात् । उत्ऽएत्य ।
तासाम् । विऽलिप्त्यम् । भीमाम् । उत्ऽआकुरुत । नारदः ॥ ४१ ॥

तां देवा अमीमांसन्त वशेया३[3]मवशेति ।
तामब्रवीन्नारद एषा वशानां वशतमेति ॥ ४२ ॥

ताम् । देवाः । अमीमांसन्त । वशा । इया३म् । अवशा३[4] । इति ।
ताम् । अब्रवीत् । नारदः । एषा । वशानाम् । वशऽतमा । इति ॥ ४२ ॥

कति नु वशा नारद यास्त्वं[5] वेत्थ मनुष्यजाः ।
तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥ ४३ ॥

कति । नु । वशाः । नारद । याः । त्वम् । वेत्थ[6] । मनुष्यऽजाः ।
ताः । त्वा । पृच्छामि । विद्वांसम् । कस्याः । न । अश्नीयात् । अब्राह्मणः ॥ ४३ ॥

विलिप्त्या बृहस्पते या च सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥ ४४ ॥

---

१ B B^h D Cs P Cp स्यात्. २ D K K^m S^m V Cs विलिप्ती. A Dc °प्तीं changed from °प्त्यं. Cp विलिप्तीं changed to विलिप्त्यं. We with B^h C E R P P^2 J. ३ So all our Saṁhitâ authorities. Also **Rw.** Against Pâṇini VIII. 2. 97, see *Chaturâdhyâyî* 1. 97. ४ So all our pada-authorities. See foregoing note. ५ **B** यास्त्तं. ६ **P** वेत्थ ।.

विऽलिप्त्याः । बृहस्पते । या । च । सूतऽवंशा । वशा ।
तस्याः । न । अश्नीयात् । अब्राह्मणः[1] । यः । आऽशंसेत । भूत्याम् ॥ ४४ ॥

नमस्ते अस्तु नारदानुष्ठु[2] विदुषे वशा ।
कतमासां भीमतमा यामदत्त्वा पराभवेत् ॥ ४५ ॥

नमः । ते । अस्तु । नारद । अनुष्ठु । विदुषे । वशा ।
कतमा । आसाम् । भीमऽतमा । याम् । अदत्त्वा । पराऽभवेत् ॥ ४५ ॥

विलिप्ती या बृहस्पतेथो सूतवंशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥ ४६ ॥

विऽलिप्ती । या । बृहस्पते । अथो इति । सूतऽवंशा । वशा ।
तस्याः । न । अश्नीयात् । अब्राह्मणः । यः । आऽशंसेत । भूत्याम् ॥ ४६ ॥

त्रीणि वै वंशाजातानि विलिप्ती सूतवंशा वशा ।
ताः[3] प्र यच्छेद् ब्रह्मभ्यः सो[4]नाव्रस्कः प्रजापतौ ॥ ४७ ॥

त्रीणि । वै । वशाऽजातानि । विऽलिप्ती । सूतऽवंशा । वशा ।
ताः । प्र । यच्छेत् । ब्रह्मऽभ्यः । सः । अनाव्रस्कः । प्रजाऽपतौ ॥ ४७ ॥

एतद् वो ब्राह्मणा[5] हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥ ४८ ॥

एतत् । वः । ब्राह्मणाः । हविः । इति । मन्वीत । याचितः ।
वशाम् । च । इत् । एनम् । याचेयुः । या । भीमा । अददुषः । गृहे ॥ ४८ ॥

देवा वशां पर्यवदन् न नोदादिति हीडिताः ।
एताभिर्ऋग्भिर्भेदं तस्माद् वै स पराभवत् ॥ ४९ ॥

देवाः । वशाम् । परि । अवदन् । न । नः । अदात् । इति । हीडिताः ।
एताभिः । ऋक्ऽभिः । भेदम् । तस्मात् । वै । सः । परा । अभवत् ॥ ४९ ॥

उतैनां भेदो नाददाद् वशामिन्द्रेण याचितः ।

---

१ P अब्राह्मणः ।. २ A $\overset{h}{\mathrm{B}}$ C D K R $\overset{m}{\mathrm{S}}$ V Dc Cs P J °नुष्ठु. Cp अनुष्ठुं ।. We with E $\overset{m}{\mathrm{K}}$ $\overset{2}{\mathrm{P}}$.
३ B ता प्र. ४ A $\overset{h}{\mathrm{B}}$ C D E K R सोना°. We with K $\overset{m}{\mathrm{S}}$ V Dc Cs. ५ C $\overset{m}{\mathrm{K}}$ ब्राह्मणा. P Cp ब्राह्मणाः ।. We with A $\overset{h}{\mathrm{B}}$ D E K R $\overset{m}{\mathrm{S}}$ V Dc Cs $\overset{2}{\mathrm{P}}$ J.

तस्मात् तं देवा आगसोवृश्चन्नहमुत्तरे ॥ ५० ॥

उत । एनाम् । भेदः । न । अददात् । वशाम् । इन्द्रेण । याचितः ।

तस्मात् । तम् । देवाः । आगसः । अवृश्चन् । अहम्ऽउत्तरे ॥ ५० ॥

ये वशाया अदानाय वदन्ति परिरापिणः ।

इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥ ५१ ॥

ये । वशायाः । अदानाय । वदन्ति । परिऽरापिणः ।

इन्द्रस्य । मन्यवे । जाल्माः । आ । वृश्चन्ते । अचित्त्या ॥ ५१ ॥

ये गोपतिं पराणीयाथाहुर्मा ददा इति ।

रुद्रस्यास्तां ते हेतिं परि यन्त्यचित्त्या ॥ ५२ ॥

ये । गोऽपतिम् । पराऽनीय । अथ । आहुः । मा । ददाः । इति ।

रुद्रस्य । अस्ताम् । ते । हेतिम् । परि । यन्ति । अचित्त्या ॥ ५२ ॥

यदि हुतां यद्यहुतामा च पचते वशाम् ।

देवान्त्सब्राह्मणानृत्वा जिह्मो लोकान्निर्ऋच्छति ॥ ५३ ॥ (२३)

यदि । हुताम् । यदि । अहुताम् । अमा । च । पचते । वशाम् ।

देवान् । सऽब्राह्मणान् । ऋत्वा । जिह्मः । लोकात् । निः । ऋच्छति ॥ ५३ ॥ (२३)

चतुर्थेनुवाके प्रथमं सूक्तम् ।

इति चतुर्थोनुवाकः ॥

ब्रह्मगवीविषयमेतत् सूक्तम् । ब्राह्मणस्य गौर्ब्रह्मगवी । तां क्षत्रियो नादद्यात् । आददाचेद् वाग् वीर्यं लक्ष्मीस्तं ह्रास्यति । ओजआदि नशिष्यति । तां क्षत्रियो न हन्यात् न पचेत् न भक्षेत् । सा हि हृता सती नानाविधा आपदो नानाविधान् मृत्यून् नानाविधानि च दुःखानि ऐहिकान्यामुष्मिकाणि आवहतीत्याह ॥

संप्रदायानुसारेणास्य सूक्तस्य विनियोगस्तु "नैतां ते देवाः" इत्यत्र [५. १८] द्रष्टव्यः ॥

श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता ॥ १ ॥

---

१ A B $\overset{h}{B}$ C D E $\overset{m}{K}$ $\overset{m}{S}$ Cs आगसो. P J आगसः ।. Cp आगसः । changed to आगसः ।. Dc आगसो° changed to आगसो°. K R अगसो. We with V Dc $\overset{2}{P}$. V, however, wrongly reads his pada as आगसः ।. २ P $\overset{2}{P}$ J एताम् ।. ३ All our authorities have तें (the pada being ते ।). Rw's correction is of course necessary. ४ P अस्ताम् ।. $\overset{2}{P}$ अस्ताम् ।. We with J Cp. ५ A C D E K $\overset{m}{K}$ V Dc Cs $\overset{2}{P}$ J Cp °निर्ऋछति. We with $\overset{h}{B}$ R P. ६ $\overset{h}{B}$ दृष्टा. ७ So we with all our authorities. See Rw.

श्रमेण । तपसा । सृष्टा । ब्रह्मणा । वित्ता । ऋते । श्रिता ॥ १ ॥

सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥ २ ॥

सत्येन । आऽवृता । श्रिया । प्रावृता । यशसा । परिऽवृता ॥ २ ॥

स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥ ३ ॥

स्वधया । परिऽहिता । श्रद्धया । परिऽऊढा । दीक्षया । गुप्ता । यज्ञे । प्रतिऽस्थिता[1] । लोकः । निऽधनम् ॥ ३ ॥

ब्रह्म पदवायं ब्राह्मणोधिपतिः ॥ ४ ॥

ब्रह्म । पदऽवायम् । ब्राह्मणः । अधिऽपतिः ॥ ४ ॥

तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥ ५ ॥

ताम् । आऽददानस्य । ब्रह्मऽगवीम् । जिनतः । ब्राह्मणम्[2] । क्षत्रियस्य ॥ ५ ॥

अप क्रामति सूनृता वीर्यं[3] पुण्या लक्ष्मीः ॥ ६ ॥ (२४)

अप । क्रामति । सूनृता । वीर्यम् । पुण्या । लक्ष्मीः ॥ ६ ॥ (२४)

इति पञ्चमेनुवाके प्रथमं पर्यायसूक्तम् ॥

ओजश्च तेजश्च सहश्च बलं च वाक् चेन्द्रियं च श्रीश्च धर्मश्च ॥ १ ॥

ओजः । च । तेजः । च । सहः । च । बलम् । च । वाक् । च । इन्द्रियम् । च । श्रीः । च । धर्मः । च ॥ १ ॥

ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥ २ ॥

ब्रह्म । च । क्षत्रम् । च । राष्ट्रम् । च । विशः । च । त्विषिः । च । यशः । च । वर्चः । च । द्रविणम् । च ॥ २ ॥

आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥३॥

आयुः । च । रूपम् । च । नाम । च । कीर्तिः । च । प्राणः । च । अपानः । च । चक्षुः । च । श्रोत्रम् । च ॥ ३ ॥

पयश्च रसश्चान्नं चान्नाद्यं चर्तं[4] च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥ ४ ॥

---

१ **P P^2 J** °स्थिताः ।. We with **V C**p. २ **P** ब्रह्मणम् ।. ३ **A B B^h D E R S^m D**c **C**s ३. We with **C K K^m V.** ४ So we with all our authorities. See **R**w.

पयः । च । रसः । च । अन्नम् । च । अन्नऽअद्यम् । च । ऋतम् । च । सत्यम् । च । इष्टम् । च । पूर्तम् । च । प्रऽजा । च । पशवः । च ॥ ४ ॥

तानि सर्वाण्यप क्रामन्ति[1] ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥ ५ ॥ (२५)

तानि । सर्वाणि । अप । क्रामन्ति । ब्रह्मऽगवीम् । आऽददानस्य । जिनतः । ब्राह्मणम्[2] । क्षत्रियस्य ॥ ५ ॥ (२५)

इति पञ्चमेनुवाके द्वितीयं पर्यायसूक्तम् ॥

सैषा भीमा ब्रह्मगव्य[3]१घविषा साक्षात् कृत्या कूल्बजमावृता ॥ १ ॥

सा । एषा । भीमा । ब्रह्मऽगवी । अघऽविषा । सऽअक्षात् । कृत्या । कूल्बजम् । आऽवृता[4] ॥ १ ॥

सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥ २ ॥

सर्वाणि । अस्याम् । घोराणि । सर्वे । च । मृत्यवः ॥ २ ॥

सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥ ३ ॥

सर्वाणि । अस्याम् । क्रूराणि । सर्वे । पुरुषऽवधाः ॥ ३ ॥

सा ब्रह्मज्यं देवपीयुं[5] ब्रह्मगव्यादीयमाना मृत्योः पड्वींश[6] आ द्यति ॥ ४ ॥

सा । ब्रह्मऽज्यम् । देवऽपीयुम् । ब्रह्मऽगवी । आऽदीयमाना । मृत्योः । पड्वींशे । आ । द्यति ॥ ४ ॥

मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥ ५ ॥

मेनिः । शतऽवधा । हि । सा । ब्रह्मऽज्यस्य । क्षितिः । हि । सा ॥ ५ ॥

तस्माद् वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥ ६ ॥

तस्मात् । वै । ब्राह्मणानाम् । गौः । दुःऽआधर्षा । विऽजानता ॥ ६ ॥

वज्रो धावन्ती वैश्वानर उद्वीता[7] ॥ ७ ॥

वज्रः । धावन्ती । वैश्वानरः । उत्ऽवीता ॥ ७ ॥

हेतिः शफानुत्खिदन्ती[8] महादेवो[9]३पेक्षमाणा ॥ ८ ॥

---

१ A B क्रामति. २ P ब्रह्मणम् ।. ३ A B B^h C D E K K^m S^m V Dc Cs ३ (A E °व्या३°). ४ P आवृता ।. ५ D S^m Cs °पीयूं. P °पीयूम् ।. ६ B °वींश. C K K^m °वींश. V Dc °विंश. We with A B^h D E R S^m Cs P P^2 J Cp. ७ E उद्वीता. ८ A B^h °खिदंति. ९ D देवो१°.

हेतिः । शफान् । उत्ऽखिदन्ती । महाऽदेवः । अपऽईक्षमाणा ॥ ८ ॥

क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥ ९ ॥

क्षुरऽपविः । ईक्षमाणा । वाश्यमाना । अभि । स्फूर्जति ॥ ९ ॥

मृत्युर्हिङ्कृण्वत्युग्रो देवः पुच्छं पर्यस्यन्ती ॥ १० ॥

मृत्युः । हिङ्ऽकृण्वती । उग्रः । देवः । पुच्छम् । परिऽअस्यन्ती ॥ १० ॥

सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥ ११ ॥

सर्वऽज्यानिः । कर्णौ । वरीवर्जयन्ती । राजऽयक्ष्मः । मेहन्ती ॥ ११ ॥

मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥ १२ ॥

मेनिः । दुह्यमाना । शीर्षक्तिः । दुग्धा ॥ १२ ॥

सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥ १३ ॥

सेदिः । उपऽतिष्ठन्ती । मिथःऽयोधः । पराऽमृष्टा ॥ १३ ॥

शरव्या३ मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥ १४ ॥

शरव्या । मुखे । अपिऽनह्यमाने । ऋतिः । हन्यमाना ॥ १४ ॥

अघविषा निपतन्ती तमो निपतिता ॥ १५ ॥

अघऽविषा । निऽपतन्ती । तमः । निऽपतिता ॥ १५ ॥

अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥ १६ ॥ (२६)

अनुऽगच्छन्ती । प्राणान् । उप । दासयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य ॥ १६ ॥ (२६)

इति पञ्चमेऽनुवाके तृतीयं पर्यायसूक्तम् ॥

वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥ १ ॥

वैरम् । विऽकृत्यमाना । पौत्रऽआद्यम् । विऽभाज्यमाना ॥ १ ॥

---

१ C स्पूर्जति. P² स्फु°. २ AB^h CEKK^m V Dc °त्यू३°. DRCs °कृण्वत्यूग्रो. S^m °कृण्वत्यूग्रो changed to °कृण्वत्यू३ग्रो. ३ PP² हिङ्कृ°. ४ K °योनः (!) ५ AB^h ER °ने ऋति°. C °नर्ऋति°. D °नेरति°. KK^m S^m V Cs °नेरिति°. Dc °न ऋति° changed to °नेरिति°. PP² J Cp °नह्यमाने ।. The context and the saṁhitâ text favor °नह्यमाना in the pada text. ६ K °हृव्यमाना.

देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥ २ ॥

देवऽहेतिः । ह्रियमाणा । विऽऋद्धिः । हृता ॥ २ ॥

पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥ ३ ॥

पाप्मा । अधिऽधीयमाना । पारुष्यम् । अवऽधीयमाना ॥ ३ ॥

विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥ ४ ॥

विषम् । प्रऽयस्यन्ती । तक्मा । प्रऽयस्ता ॥ ४ ॥

अघं पच्यमाना दुष्वप्न्यं पक्वा ॥ ५ ॥

अघम् । पच्यमाना । दुःऽस्वप्न्यम् । पक्वा ॥ ५ ॥

मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥ ६ ॥

मूलऽबर्हणी । परिऽआक्रियमाणा । क्षितिः । परिऽआकृता ॥ ६ ॥

असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥ ७ ॥

असम्ऽज्ञा । गन्धेन । शुक् । उद्ध्रियमाणा । आशीविषः । उद्धृता ॥ ७ ॥

अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥ ८ ॥

अभूतिः । उपऽह्रियमाणा । पराऽभूतिः । उपऽहृता ॥ ८ ॥

शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥ ९ ॥

शर्वः । क्रुद्धः । पिश्यमाना । शिमिदा । पिशिता ॥ ९ ॥

अवर्तिरश्यमाना निर्ऋतिरशिता ॥ १० ॥

अवर्तिः । अश्यमाना । निःऽऋतिः । अशिता ॥ १० ॥

अशिता लोकांच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥ ११ ॥ (२७)

अशिता । लोकान् । छिनत्ति । ब्रह्मऽगवी । ब्रह्मऽज्यम् । अस्मात् । च । अमुष्मात् । च ॥ ११ ॥ (२७)

इति पञ्चमेनुवाके चतुर्थं पर्यायसूक्तम् ॥

---

१ A C D E R S̈ Cs °हेतिर्हृयमाणा. We with K K̈ V Dc P P̈ J Cp. २ E R व्यृद्धिर्हृता. B̈ वृद्धिर्हृता. We with A C D K K̈ S̈ V Dc Cs. ३ P देवाऽहेतिः।. ४ P ऋता।. ५ B̈ E प्रयछन्ती. ६ A शकुध्रि°. B शनुकुध्रि°. D K K̈ S̈ V Dc Cs शगुध्रि°. We with B̈ C E R. ७ B उद्धता. ८ P P̈ J Cp उध्रिय°।. ९ P °नाः।. १० B̈ C K K̈ S̈ V लोकांछि°. We with A B D E R P P̈ J Cp.

तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम ॥ १ ॥

तस्याः । आऽहननम् । कृत्या । मेनिः । आऽशसनम् । वलगः । ऊबध्यम् ॥ १ ॥

अस्वगता परिह्णुता ॥ २ ॥

अस्वगता । परिऽह्णुता ॥ २ ॥

अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥ ३ ॥

अग्निः । क्रव्यऽअत् । भूत्वा । ब्रह्मऽगवी । ब्रह्मऽज्यम् । प्रऽविश्य । अत्ति ॥ ३ ॥

सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥ ४ ॥

सर्वा । अस्य । अङ्गा । पर्वा । मूलानि । वृश्चति ॥ ४ ॥

छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥ ५ ॥

छिनत्ति । अस्य । पितृऽबन्धु । परा । भावयति । मातृऽबन्धु ॥ ५ ॥

विवाहां ज्ञातीन्त्सर्वानपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दी-यमाना ॥ ६ ॥

विऽवाहान् । ज्ञातीन् । सर्वान् । अपि । क्षापयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य । क्षत्रियेण । अपुनःऽदीयमाना ॥ ६ ॥

अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥ ७ ॥

अवास्तुम् । एनम् । अस्वगम् । अप्रजसम् । करोति । अपराऽपरणः । भवति । क्षीयते ॥ ७ ॥

य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥ ८ ॥ (२८)

यः । एवम् । विदुषः । ब्राह्मणस्य । क्षत्रियः । गाम् । आऽदत्ते ॥ ८ ॥ (२८)

इति पञ्चमेनुवाके पञ्चमं पर्यायसूक्तम् ॥

क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥ १ ॥

क्षिप्रम् । वै । तस्य । आऽहनने । गृध्राः । कुर्वते । ऐलबम् ॥ १ ॥

क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनी-
राघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥ २ ॥

---

१ B S परिह्नुता (may be °ह्णु°). We with A C D E K K V P P J Cp. २ A B B D K K V Dc °पुनर्दीयमाना. P अपुनःऽदीयमाना ।. V Cp अपुनः । दीयमाना ।. Cs °पुनर्दीयमाना. We with C E R S P J. ३ B भवति. ४ P एलबम् ।. We with P J Cp.

°तस्य॑ । आ॒ऽदह॑नम् । परि॑ । नृ॒त्यन्ति॑ । के॒शिनीः॑ ।
आ॒ऽघ्नानाः॑ । पा॒णिना॑ । उर॑सि । कु॒र्वा॒णाः । पा॒पम् । ऐ॒ल॒बम् ॥ २ ॥

क्षि॒प्रं वै तस्य॑ वास्तु॑षु वृका॑ः कुर्वत ऐल॒बम् ॥ ३ ॥

°तस्य॑ । वास्तु॑षु । वृका॑ः । कु॒र्व॒ते । ऐ॒ल॒बम् ॥ ३ ॥

क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत् तदासी॑३दि॒दं नु ता३दिति॑ ॥ ४ ॥

क्षि॒प्रम् । वै । तस्य॑ । पृ॒च्छन्ति॑ । यत् । तत् । आसी॑३त् । इ॒दम् । नु । ता३त् । इति॑ ॥ ४ ॥

छि॒न्ध्या च्छि॑न्धि॒ प्र च्छि॒न्ध्यपि॑ क्षापय क्षा॒पय॑ ॥ ५ ॥

छि॒न्धि । आ । छि॒न्धि॒ । प्र । छि॒न्धि॒ । अपि॑ । क्षा॒प॒य॒ । क्षा॒पय॑ ॥ ५ ॥

आ॒दर्दा॑नमाङ्गिर॑सि ब्रह्म॒ज्यमुप॑ दासय ॥ ६ ॥

आ॒ऽदर्दा॑नम् । आ॒ङ्गि॒र॒सि॒ । ब्र॒ह्म॒ऽज्यम् । उप॑ । दा॒स॒य॒ ॥ ६ ॥

वै॒श्व॒दे॒वी ह्यु१॒च्यसे॑ कृ॒त्या कूल्ब॑ज॒मावृ॑ता ॥ ७ ॥

वै॒श्व॒ऽदे॒वी । हि । उ॒च्यसे॑ । कृ॒त्या । कू॒ल्ब॑जम् । आऽवृ॑ता ॥ ७ ॥

ओष॑न्ती॒ स॒मोष॑न्ती॒ ब्रह्म॑णो॒ वज्र॑ः ॥ ८ ॥

ओष॑न्ती । स॒म्ऽओष॑न्ती । ब्रह्म॑णः । वज्र॑ः ॥ ८ ॥

क्षु॒रप॑वि॒र्मृ॒त्युर्भू॒त्वा वि धा॑व॒ त्वम् ॥ ९ ॥

क्षु॒रऽप॑विः । मृ॒त्युः । भू॒त्वा । वि । धा॒व॒ । त्वम् ॥ ९ ॥

आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिष॑ः ॥ १० ॥

आ । द॒त्से॒ । जि॒न॒ताम् । वर्च॑ः । इ॒ष्टम् । पू॒र्तम् । च॒ । आ॒ऽशिष॑ः ॥ १० ॥

आ॒दाय॑ जी॒तं जी॒ताय॑ लो॒के॒३॒ऽमुष्मि॒न् प्र य॑च्छसि ॥ ११ ॥

आ॒ऽदाय॑ । जी॒तम् । जी॒ताय॑ । लो॒के । अ॒मुष्मि॑न् । प्र । य॒च्छ॒सि॒ ॥ ११ ॥

---

१ B तस्या. २ K K̈ᵐ V तदासीदि॒दं नु ता३दिति॑. D Cs तदासी॑१दि॒दं नु ता१दिति॑. C तदासी॑दि॒दं नु ता३दिति॑. S̈ᵐ तदासी३दि॒दं नु ता१दिति॑. P आसी॑त् ३ । तात् ३ ।. P̈² आसी३त् । ता३त् ।. Cp आ॒सीत् । इ॒दं । नु । तात् । changed to आसी॑त् । इ॒दं । नु । तात् ३ ।. J आसी॑३त् । ता३त् ।. A B̈ʰ E R Dc. तदासी॑३दि॒दं नु ता३दिति॑. ३ B K̈ᵐ °र॒सिब्र॑°. ४ P आं॒गि॒र॒सि ।. ५ D Cs °ह्यू॒° (no kampa). E R °ह्यु३°. K °ह्यू१°. V °ह्यु१°. Dc °ह्यु॒१°. A B̈ʰ C °ह्यू॒३°. ६ P̈² कू॒ल्ब॑जम् ।. ७ B लो॒के॒१°.

अघ्न्ये[१] पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥ १२ ॥

अघ्न्ये । पदऽवीः । भव । ब्राह्मणस्य । अभिऽशस्त्या ॥ १२ ॥

मेनिः शरव्या भवाघादघविषा भव ॥ १३ ॥

मेनिः । शरव्या । भव । अघात् । अघऽविषा । भव ॥ १३ ॥

अघ्न्ये[२] प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥ १४ ॥

अघ्न्ये । प्र । शिरः । जहि । ब्रह्मऽज्यस्य । कृतऽआगसः । देवऽपीयोः । अराधसः ॥ १४ ॥

त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥ १५ ॥ (२९)

त्वया । प्रऽमूर्णम् । मृदितम् । अग्निः । दहतु । दुःऽचितम् ॥ १५ ॥ (२९)

इति पञ्चमेऽनुवाके षष्ठं पर्यायसूक्तम् ॥

वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥ १ ॥

वृश्च । प्र । वृश्च । सम् । वृश्च । दह । प्र । दह । सम् । दह ॥ १ ॥

ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥ २ ॥

ब्रह्मऽज्यम् । देवि । अघ्न्ये । आ । मूलात् । अनुऽसंदह ॥ २ ॥

यथायाद्[३] यमसादनात् पापलोकान् परावतः ॥ ३ ॥

यथा । अयात्[३] । यमऽसदनात् । पापऽलोकान् । पराऽवतः ॥ ३ ॥

एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥ ४ ॥

एव । त्वम् । देवि । अघ्न्ये । ब्रह्मऽज्यस्य । कृतऽआगसः । देवऽपीयोः । अराधसः ॥ ४ ॥

वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥ ५ ॥

वज्रेण । शतऽपर्वणा । तीक्ष्णेन । क्षुरऽभृष्टिना ॥ ५ ॥

प्र स्कन्धान् प्र शिरो जहि ॥ ६ ॥

प्र । स्कन्धान् । प्र । शिरः । जहि ॥ ६ ॥

लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥ ७ ॥

लोमानि । अस्य । सम् । छिन्धि । त्वचम् । अस्य । वि । वेष्टय ॥ ७ ॥

---

१ R S^m अघ्न्ये. २ R अघ्न्ये. ३ So our authorities of saṁhitâ and pada respectively. We should expect यथा याद् यम° and यथा । यात् । यम° ।.

मांसान्यस्य शातय स्नावान्यस्य सं वृंह ॥ ८ ॥

मांसानि । अस्य । शातय । स्नावानि । अस्य । सम् । वृह ॥ ८ ॥

अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥ ९ ॥

अस्थीनि । अस्य । पीडय । मज्जानम् । अस्य । निः । जहि ॥ ९ ॥

सर्वास्याङ्गा पर्वाणि वि श्रथय ॥ १० ॥

सर्वा । अस्य । अङ्गा । पर्वाणि । वि । श्रथय ॥ १० ॥

अग्निरेनं क्रव्यात् पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः ॥ ११ ॥

अग्निः । एनम् । क्रव्यऽअत् । पृथिव्याः । नुदताम् । उत् । ओषतु । वायुः । अन्तरिक्षात् । महतः । वरिम्णः ॥ ११ ॥

सूर्य एनं दिवः प्र णुदतां न्योषतु ॥ १२ ॥ (३०)

सूर्यः । एनम् । दिवः । प्र । नुदताम् । नि । ओषतु ॥ १२ ॥ (३०)

पञ्चमेनुवाके सप्तमं पर्यायसूक्तम् ॥

पञ्चमोनुवाकः ॥

इति द्वादशं काण्डं समाप्तम् ॥

---

१ D E K[m] S[m] वृंह. Cp वृह ।. We with A B[h] C K R V Dc Cs P P[2] J. २ J V Cp विश्र° ।. P[2] वि । श्रथय ।. P विश्रथय ।.

"उदेहि वाजिन्" इति सूक्तं रोहितदेवताकम् । रोहितः कश्चिद् देवः । उद्यन् यः सूर्यस्तदात्मक इति ज्ञेयम् । रोहितसाहचर्येण मरुतः इन्द्रः अज एकपादः अग्निः सविता मित्रावरुणौ क्रव्याद् अग्निः सूर्य इत्यादयो देवा अप्याहूता वर्णिताश्च । रोहितस्य तथा तत्संबन्धिदेवानामत्र वर्णने प्रयोजनं राज्ञो राष्ट्रस्य भरणम् इति सूक्त इतस्ततो द्रष्टव्यम् ॥

क्वचिन्मन्त्रेषु रोहितपदस्य निर्वचनं रुहो रुरोह प्ररुहो रुरोह द्यावापृथिवीभ्यां रुरोहेति रोहित इति ध्वनितम् ॥

याज्ञिकास्तु वक्ष्यमाणप्रकारेण विनियुञ्जन्ति । तद्यथा ।

अर्थकामः "उदेहि वाजिन्" इत्यादिविंशत्यृग्भिरुद्यन्तम् आदित्यम् उपतिष्ठते ॥

तथा अर्थोत्थापनकामः उक्तविंशत्यृग्भिः स्नानं कृत्वा उपतिष्ठते ॥

तथा अर्थसिद्धिकामः अहतवस्त्रपरिधानं कृत्वा उक्ताभिर्ऋग्भिरुपतिष्ठते ॥

तथा अर्थो मम सिध्यताम् एवंकामस्ताभिर्ऋग्भिर्वस्त्रम् अभिमन्त्र्य परिधापयति ॥

तथा विद्रावणादिविषये शमनकामः उक्ताभिर्ऋग्भिर्वस्त्रम् अभिमन्त्र्य ददाति ॥

सूत्रितं हि । "°उत्तमेन [६. ६२] वाचस्पतिलिङ्गाभिरुद्यन्तम् उपतिष्ठते । स्नातोऽहतवसनो निक्त्वाहतम् आच्छादयते ददाति" इति । कौ° ५. ५ ॥ उदेहि वाजिन्निति विंशत्यृचो वाचस्पतिलिङ्गा इति केशवः ॥

"यो रोहितः" इति द्वयोर्ऋचोः [२५, २६] सलिलगणे पाठः । अतः "सलिलैः क्षीरौदनम् अश्नाति मन्थान्तानि" [कौ° ३. १] "सलिलैः सर्वकामः" [कौ° ३. ७] इत्यादौ चास्य विनियोगः ॥ सलिलगणश्च "आपो हि ष्ठा" इति १. ५ सूक्ते द्रष्टव्यः ॥

"समिद्धो अग्निः समिधानो घृतवृद्धः" इति [२८–३२] पञ्चर्चस्य विनियोगो "य इमे द्यावापृथिवी" [१३. ३] इत्यत्र द्रष्टव्यः ॥

उदेहि वाजिन् यो अप्स्व१न्तरिदं राष्ट्रं प्र विश सूनृतावत् ।
यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥ १ ॥

उत्ऽएहि । वाजिन् । यः । अप्ऽसु । अन्तः । इदम् । राष्ट्रम् । प्र । विश । सूनृताऽवत् ।
यः । रोहितः । विश्वम् । इदम् । जजान । सः । त्वा । राष्ट्राय । सुऽभृतम् । बिभर्तु ॥ १ ॥

उद्वाज आ गन् यो अप्स्व१न्तर्विश आ रोह त्वद्योनयो याः ।
सोमं दधानोप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥ २ ॥

उत् । वाजः । आ । गन् । यः । अप्ऽसु । अन्तः । विशः । आ । रोह । त्वत्ऽयोनयः । याः ।
सोमम् । दधानः । अपः । ओषधीः । गाः । चतुःऽपदः । द्विऽपदः । आ । वेशय । इह ॥ २ ॥

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।

१ B $\overset{h}{\text{B}}$ C D E R $\overset{m}{\text{S}}$ Cs ३. We with K $\overset{m}{\text{K}}$ V Dc.

आ वो रोहितः शृणवत् सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥ ३ ॥

यूयम् । उग्राः । मरुतः । पृश्निऽमातरः । इन्द्रेण । युजा । प्र । मृणीत । शत्रून् ।
आ । वः । रोहितः । शृणवत् । सुऽदानवः । त्रिऽसप्तासः । मरुतः । स्वादुऽसंमुदः ॥ ३ ॥

रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्निह राष्ट्रमाहाः ॥ ४ ॥

रुहः । रुरोह । रोहितः । आ । रुरोह । गर्भः । जनीनाम् । जनुषाम् । उपऽस्थम् ।
ताभिः । सम्ऽरब्धम् । अनु । अविन्दन् । षट् । उर्वीः । गातुम् । प्रऽपश्यन् । इह । राष्ट्रम् । आ । अहाः ॥ ४ ॥

आ ते राष्ट्रमिह रोहितोहार्षीद् व्यास्थन्मृधो अभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्करीभिः ॥ ५ ॥

आ । ते । राष्ट्रम् । इह । रोहितः । अहार्षीत् । वि । आस्थत् । मृधः । अभयम् । ते । अभूत् ।
तस्मै । ते । द्यावापृथिवी इति । रेवतीभिः । कामम् । दुहाथाम् । इह । शक्करीभिः ॥ ५ ॥

रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
तत्र शिश्रियेज एकपादोदृंहद् द्यावापृथिवी बलेन ॥ ६ ॥

रोहितः । द्यावापृथिवी इति । जजान । तत्र । तन्तुम् । परमेऽस्थी । ततान ।
तत्र । शिश्रिये । अजः । एकऽपादः । अदृंहत् । द्यावापृथिवी इति । बलेन ॥ ६ ॥

रोहितो द्यावापृथिवी अदृंहत् तेन स्वः स्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥ ७ ॥

रोहितः । द्यावापृथिवी इति । अदृंहत् । तेन । स्वः । स्तभितम् । तेन । नाकः ।
तेन । अन्तरिक्षम् । विऽमिता । रजांसि । तेन । देवाः । अमृतम् । अनु । अविन्दन् ॥ ७ ॥

वि रोहितो अमृशद् विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।
दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥ ८ ॥

---

१ K $\overset{m}{K}$ V Dc संरभध्व°. २ A D $\overset{m}{S}$ Cs °तो अहार्षी°. We with $\overset{h}{B}$ C E K $\overset{m}{K}$ R V Dc. ३ $\overset{h}{B}$ C E R $\overset{m}{S}$ °द्यास्थ° for °द् व्यास्थ°. We with A D K $\overset{m}{K}$ V. ४ A $\overset{h}{B}$ C D E K $\overset{m}{K}$ R $\overset{m}{S}$ V Dc Cs दुहाथा°. P $\overset{2}{P}$ J Cp दुहाथाम् ।. The emendation to °ता° adopted by Rw. is not inevitable, though desirable. ५ P रेवतिभिः ।. ६ B $\overset{h}{B}$ D E R $\overset{m}{S}$ स्व. ७ R रुद्वा.

वि । रोहितः । अमृशत् । विश्वऽरूपम् । सम्ऽआकुर्वाणः । प्रऽरुहः । रुहः । च ।
दिवम् । रूढ्वा । महता । महिम्ना । सम् । ते । राष्ट्रम् । अनक्तु । पयसा । घृतेन ॥ ८ ॥

यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥ ९ ॥

याः । ते । रुहः । प्रऽरुहः । याः । ते । आऽरुहः । याभिः । आऽपृणासि । दिवम् । अन्तरिक्षम् ।
तासाम् । ब्रह्मणा । पयसा । ववृधानः । विशि । राष्ट्रे । जागृहि । रोहितस्य ॥ ९ ॥

यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥(१)

याः । ते । विशः । तपसः । सम्ऽबभूवुः । वत्सम् । गायत्रीम् । अनु । ताः । इह । आ । अगुः ।
ताः । त्वा । आ । विशन्तु । मनसा । शिवेन । सम्ऽमाता । वत्सः । अभि । एतु । रोहितः ॥ १० ॥ (१)

ऊर्ध्वो रोहितो अधि नाके अस्थाद् विश्वा रूपाणि जनयन् युवा कविः ।
तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥ ११ ॥

ऊर्ध्वः । रोहितः । अधि । नाके । अस्थात् । विश्वा । रूपाणि । जनयन् । युवा । कविः ।
तिग्मेन । अग्निः । ज्योतिषा । वि । भाति । तृतीये । चक्रे । रजसि । प्रियाणि ॥ ११ ॥

सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।
मा मा हासीन्नाथितो नेत् त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥

सहस्रऽशृङ्गः । वृषभः । जातऽवेदाः । घृतऽआहुतः । सोमऽपृष्ठः । सुऽवीरः[१] ।
मा । मा । हासीत् । नाथितः । न । इत् । त्वा । जहानि । गोऽपोषम् । च । मे । वीरऽपोषम् । च । धेहि ॥ १२ ॥

रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
रोहितं देवा यन्ति सुमनस्यमाना सं[२] मा रोहैः सामित्यै रोहयतु ॥ १३ ॥

रोहितः । यज्ञस्य । जनिता । मुखम् । च । रोहिताय । वाचा । श्रोत्रेण । मनसा । जुहोमि ।
रोहितम् । देवाः । यन्ति । सुऽमनस्यमानाः । सः । मा । रोहैः । साम्ऽइत्यै । रोहयतु ॥ १३ ॥

---

१ P सुऽवीराः ।. २ R सं.

रोहितो यज्ञं व्यदधाद् विश्वकर्मणे तस्मात् तेजांस्युप मेमान्यागुः ।
वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥ १४ ॥

रोहितः । यज्ञम् । वि । अदधात् । विश्वऽकर्मणे । तस्मात् । तेजांसि । उप । मा । इमानि । आ । अगुः ।
वोचेयम् । ते । नाभिम् । भुवनस्य । अधि । मज्मनि ॥ १४ ॥

आ त्वा रुरोह बृहत्युऽत पङ्क्तिरा ककुब् वर्चसा जातवेदः ।
आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥ १५ ॥

आ । त्वा । रुरोह । बृहती । उत । पङ्क्तिः । आ । ककुप् । वर्चसा । जातऽवेदः ।
आ । त्वा । रुरोह । उष्णिहाऽअक्षरः । वषट्ऽकारः । आ । त्वा । रुरोह । रोहितः । रेतसा । सह ॥ १५ ॥

अयं वस्ते गर्भं पृथिव्या दिवं वस्तेयमन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥ १६ ॥

अयम् । वस्ते । गर्भम् । पृथिव्याः । दिवम् । वस्ते । अयम् । अन्तरिक्षम् ।
अयम् । ब्रध्नस्य । विष्टपि । स्वः । लोकान् । वि । आनशे ॥ १६ ॥

वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥ १७ ॥

वाचः । पते । पृथिवी । नः । स्योना । स्योना । योनिः । तल्पा । नः । सुऽशेवा ।
इह । एव । प्राणः । सख्ये । नः । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अग्निः । आयुषा । वर्चसा । दधातु ॥ १७ ॥

वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।

---

१ B C D E R S^m Cs P P^2 J Cp मय्मनि. Dc मय्मनि changed to मज्मनि. २ C D Dc Cs °हत्यूऽत. E °हत्युऽत्त. R °हत्युत्त. S^m °हत्यूऽत. ३ B^h दिवं च वस्ते°. ४ D E S^m Cs नं स्योना. ५ B E K K^m R सुशेवाः. We with A B^h C D S^m V Dc Cs P P^2 J Cp. ६ So P P^2 J Cp, and not तल्पाः ।. ७ A B^h C D E K R S^m V Dc Cs P P^2 J Cp ये नौ. B K^m read योनौ for ये नौ. The passage is not free from suspicion of corruption.

इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥ १८ ॥

°पते । ऋतवः । पञ्च । ये । नौ । वैश्वऽकर्मणाः । परि । ये । सम्ऽबभूवुः ।
°परि । रोहितः । आयुषा । वर्चसा । दधातु ॥ १८ ॥

वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधामि ॥ १९ ॥

वाचः । पते । सौमनसम् । मनः । च । गोऽस्थे । नः । गाः । जनय । योनिषु । प्रऽजाः ।
इह । एव । प्राणः । सख्ये । नः । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अहम् । आयुषा । वर्चसा । दधामि ॥ १९ ॥

परि त्वा धात् सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।
सर्वा अरातीरवक्रामन्नेहीदं राष्ट्रमकरः सूनृतावत् ॥ २० ॥(२)

परि । त्वा । धात् । सविता । देवः । अग्निः । वर्चसा । मित्रावरुणौ । अभि । त्वा ।
सर्वाः । अरातीः । अवऽक्रामन् । आ । इहि । इदम् । राष्ट्रम् । अकरः । सूनृताऽवत् ॥ २० ॥(२)

यं त्वा पृषती रथे प्रष्टिर्[१]वहति रोहित[२] ।
शुभा यासि रिणन्[३]नपः ॥ २१ ॥

यम् । त्वा । पृषती । रथे । प्रष्टिः[१] । वहति । रोहित[२] ।
शुभा । यासि । रिणन्[३] । अपः ॥ २१ ॥

अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।
तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम[४] ॥ २२ ॥

अनुऽव्रता । रोहिणी । रोहितस्य । सूरिः । सुऽवर्णा । बृहती । सुऽवर्चाः ।
तया । वाजान् । विश्वऽरूपान्[५] । जयेम । तया । विश्वाः । पृतनाः । अभि । स्याम ॥ २२ ॥

---

१ A प्रष्ठि°. B^h C K K^m V Dc P P^2 Cp पृष्टि°. S^m प्रष्टि° changed to प्रष्ठि°. We with D E R Cs J. २ B^h R S^m Cs रोहितः. P Cp रोहितः ।. ३ B E K R P P^2 J ऋणन्नपः. S^m यासि रि° changed to यास्यृ°. We with A B^h C D K^m V Dc Cs Cp. ४ C स्याम. ५ P P^2 J °रूपाम् ।. Cp °रूपां ।.

इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।
तां[1] गन्धर्वाः[2] कश्यपा उन्नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥ २३ ॥

इदम् । सदः । रोहिणी[3] । रोहितस्य । असौ । पन्थाः । पृषती । येन । याति ।
ताम् । गन्धर्वाः । कश्यपाः । उत् । नयन्ति । ताम् । रक्षन्ति । कवयः । अप्रऽमादम् ॥ २३ ॥

सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।
घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥ २४ ॥

सूर्यस्य । अश्वाः । हरयः । केतुऽमन्तः । सदा । वहन्ति । अमृताः । सुऽखम् । रथम् ।
घृतऽपावा । रोहितः । भ्राजमानः । दिवम् । देवः । पृषतीम् । आ । विवेश ॥ २४ ॥

यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।
यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते ॥ २५ ॥

यः । रोहितः । वृषभः । तिग्मऽशृङ्गः । परि । अग्निम् । परि । सूर्यम् । बभूव ।
यः । विऽस्तभ्नाति । पृथिवीम् । दिवम् । च । तस्मात् । देवाः । अधि । सृष्टीः । सृजन्ते ॥ २५ ॥

रोहितो दिवमारुहन्महतः पर्यर्णवात् ।
सर्वा रुरोह रोहितो रुहः ॥ २६ ॥

रोहितः । दिवम् । आ । अरुहत् । महतः । परि । अर्णवात् ।
सर्वाः । रुरोह । रोहितः । रुहः ॥ २६ ॥

वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।
इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥ २७ ॥

वि । मिमीष्व । पयस्वतीम् । घृताचीम् । देवानाम् । धेनुः । अनपऽस्पृक् । एषा ।
इन्द्रः । सोमम् । पिबतु । क्षेमः । अस्तु । अग्निः । प्र । स्तौतु । वि । मृधः । नुदस्व ॥ २७ ॥

समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।
अभीषाड् विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥ २८ ॥

---

१ D Cs तान् for तां. २ A B B^h C D E K K^m R S^m Cs गंधर्वाः. Dc गंधर्वाः changed to गंधर्वाः. P J Cp गंधर्वाः ।. We with V Dc P^2. ३ P P^2 J रोहिणीः ।. We with Cp.

सम्ऽइद्धः । अग्निः । सम्ऽइधानः । घृतऽवृद्धः । घृतऽआहुतः ।

अभीषाट् । विश्वाषाट् । अग्निः । सऽपत्नान् । हन्तु । ये । मम ॥ २८ ॥

हन्त्वेनान् प्र दहत्वरि[1]र्यो नः पृतन्यति ।

क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥ २९ ॥

हन्तु । एनान्[2] । प्र । दहतु । अरिः । यः । नः । पृतन्यति ।

क्रव्यऽअदा । अग्निना । वयम् । सऽपत्नान् । प्र । दहामसि ॥ २९ ॥

अवा[3]चीनानव जहीन्द्र वज्रेण बाहुमान् ।

अधा सपत्नान् मामकानग्नेस्तेजोभिरादिषि ॥ ३० ॥(३)

अवाचीनान् । अव । जहि । इन्द्र । वज्रेण । बाहुऽमान् ।

अध । सऽपत्नान् । मामकान् । अग्नेः । तेजःऽभिः । आ । अदिषि ॥ ३० ॥(३)

अग्ने सपत्नानधरान् पादयास्मद् व्यथया सजातमुत्पिपानं बृहस्पते ।

इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥ ३१ ॥

अग्ने । सऽपत्नान् । अधरान् । पादय । अस्मत् । व्यथय । सऽजातम् । उत्ऽपिपानम् ।
बृहस्पते ।

इन्द्राग्नी इति । मित्रावरुणौ । अधरे । पद्यन्ताम् । अप्रतिऽमन्यूयमानाः ॥ ३१ ॥

उद्यंस्त्वं देव सूर्य सपत्नानव मे जहि ।

अवैनानश्मना जहि ते यन्त्वधमं तमः ॥ ३२ ॥

उत्ऽयन् । त्वम् । देव । सूर्य । सऽपत्नान् । अव । मे । जहि ।

अव । एनान् । अश्मना । जहि । ते । यन्तु । अधमम् । तमः ॥ ३२ ॥

वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठो[4]ऽन्तरिक्षम् ।

घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥ ३३ ॥

वत्सः । विऽराजः । वृषभः । मतीनाम् । आ । रुरोह । शुक्रऽपृष्ठः । अन्तरिक्षम् ।

घृतेन । अर्कम् । अभि । अर्चन्ति । वत्सम् । ब्रह्म । सन्तम् । ब्रह्मणा । वर्धयन्ति ॥ ३३ ॥

दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।

---

१ K दहत्वग्निर्यो. २ P^2 एनाम् ।. ३ B अर्वाची°. ४ B B^h R Cs P^2 °पृष्ठो°.

प्रजां च रोहामृतं च रोह रोहितेन तन्वं१ सं स्पृशस्व ॥ ३४ ॥

दिवम् । च । रोह । पृथिवीम् । च । रोह । राष्ट्रम् । च । रोह । द्रविणम् । च । रोह ।
प्रऽजाम् । च । रोह । अमृतम् । च । रोह । रोहितेन । तन्वम् । सम् । स्पृशस्व ॥ ३४ ॥

ये देवा राष्ट्रभृतोभितो यन्ति सूर्यम् ।
तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥ ३५ ॥

ये । देवाः । राष्ट्रऽभृतः । अभितः । यन्ति । सूर्यम् ।
तैः । ते । रोहितः । सम्ऽविदानः । राष्ट्रम् । दधातु । सुऽमनस्यमानः ॥ ३५ ॥

उत त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।
तिरः समुद्रमति रोचसे२र्णवम् ॥ ३६ ॥

उत । त्वा । यज्ञाः । ब्रह्मऽपूताः । वहन्ति । अध्वऽगतः । हरयः । त्वा । वहन्ति ।
तिरः । समुद्रम् । अति । रोचसे । अर्णवम् ॥ ३६ ॥

रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।
सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि३॥३७॥

रोहिते । द्यावापृथिवी इति । अधि । श्रिते इति । वसुऽजिति । गोऽजिति । संधनऽजिति ।
सहस्रम् । यस्य । जनिमानि । सप्त । च । वोचेयम् । ते । नाभिम् । भुवनस्य । अधि ।
मज्मनि३ ॥ ३७ ॥

यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।
यशाः पृथिव्या अदित्या उपस्थेहं भूयासं सवितेव चारुः ॥ ३८ ॥

यशाः । यासि । प्रऽदिशः । दिशः । च । यशाः । पशूनाम् । उत । चर्षणीनाम् ।
यशाः । पृथिव्याः । अदित्याः । उपऽस्थे । अहम् । भूयासम् । सविताऽइव । चारुः ॥ ३८ ॥

अमुत्र सन्निह वेत्थेतः संस्तानि पश्यसि ।
इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥ ३९ ॥

अमुत्र । सन् । इह । वेत्थ । इतः । सन् । तानि । पश्यसि ।
इतः । पश्यन्ति । रोचनम् । दिवि । सूर्यम् । विपःऽचितम् ॥ ३९ ॥

---

१ B B[h] C D S[m] Cs ३ for १. We with A K K[m] V Dc. २ A R S[m] रोचसे अर्णवम्. ३ B D E R S[m] Cs P P[2] J Cp मत्मनि. We with C Dc.

देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।
समानमग्निमिन्धते तं विदुः कवयः परे ॥ ४० ॥ (४)

देवः । देवान् । मर्चयसि । अन्तः । चरसि । अर्णवे ।
समानम् । अग्निम् । इन्धते । तम् । विदुः । कवयः । परे ॥ ४० ॥ (४)

अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात् क्व स्वित् सूते नहि यूथे अस्मिन् ॥ ४१ ॥

अवः । परेण । परः । एना । अवरेण । पदा । वत्सम् । बिभ्रती । गौः । उत् । अस्थात् ।
सा । कद्रीची । कम् । स्वित् । अर्धम् । परा । अगात् । क्व । स्वित् । सूते । नहि । यूथे ।
अस्मिन् ॥ ४१ ॥

एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।
सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥ ४२ ॥

एकऽपदी । द्विऽपदी । सा । चतुःऽपदी । अष्टाऽपदी । नवऽपदी । बभूवुषी ।
सहस्रऽअक्षरा । भुवनस्य । पङ्क्तिः । तस्याः । समुद्राः । अधि । वि । क्षरन्ति ॥ ४२ ॥

आरोहन् द्याममृतः प्राव मे वचः ।
उत् त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥ ४३ ॥

आऽरोहन्[1] । द्याम् । अमृतः । प्र । अव[2] । मे । वचः ।
उत् । त्वा । यज्ञाः । ब्रह्मऽपूताः । वहन्ति । अध्वऽगतः । हरयः । त्वा । वहन्ति ॥ ४३ ॥

वेद तत् ते अमर्त्य यत् त आक्रमणं दिवि ।
यत् ते सधस्थं परमे व्योमन् ॥ ४४ ॥

वेद । तत् । ते । अमर्त्य । यत् । ते । आऽक्रमणम् । दिवि ।
यत् । ते । सधऽस्थम् । परमे । विऽओमन् ॥ ४४ ॥

सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोति पश्यति ।
सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥ ४५ ॥

सूर्यः । द्याम् । सूर्यः । पृथिवीम् । सूर्यः । आपः । अति । पश्यति ।
सूर्यः । भूतस्य । एकम् । चक्षुः । आ । रुरोह । दिवम् । महीम् ॥ ४५ ॥

---

१ J आऽरोहम् ।. २ P J Cp अव ।. We with P[2].

उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।
तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥ ४६ ॥

उर्वीः । आसन् । परिऽधयः । वेदिः । भूमिः । अकल्पत ।
तत्र । एतौ । अग्नी इति । आ । अधत्त । हिमम् । घ्रंसम् । च । रोहितः ॥ ४६ ॥

हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥ ४७ ॥

हिमम् । घ्रंसम् । च । आऽधाय । यूपान् । कृत्वा । पर्वतान् ।
वर्षऽआज्यौ । अग्नी इति । ईजाते इति । रोहितस्य । स्वःऽविदः ॥ ४७ ॥

स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।
तस्माद् घ्रंसस्तस्माद्धिमस्तस्माद् यज्ञोऽजायत[1] ॥ ४८ ॥

स्वःऽविदः । रोहितस्य । ब्रह्मणा । अग्निः । सम् । इध्यते ।
तस्मात् । घ्रंसः । तस्मात् । हिमः । तस्मात् । यज्ञः । अजायत ॥ ४८ ॥

ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ ४९ ॥

ब्रह्मणा । अग्नी इति । ववृधानौ । ब्रह्मऽवृद्धौ । ब्रह्मऽआहुतौ ।
ब्रह्मऽइद्धौ[2] । अग्नी इति । ईजाते इति । रोहितस्य । स्वःऽविदः ॥ ४९ ॥

सत्ये अन्यः समाहितोऽप्स्व१न्यः[3] समिध्यते ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ ५० ॥(५)

सत्ये । अन्यः । सम्ऽआहितः । अप्ऽसु । अन्यः । सम् । इध्यते ।० ॥ ५० ॥(५)

यं वातः परि शुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ ५१ ॥

यम् । वातः । परिऽशुम्भति । यम् । वा । इन्द्रः । ब्रह्मणः । पतिः ।
ब्रह्मऽइद्धौ[4] । अग्नी इति । ईजाते इति । रोहितस्य । स्वःऽविदः ॥ ५१ ॥

वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।

---

१ E यज्ञोजायत. २ P Cp ब्रह्मऽइध्यौ ।. We with P J. ३ BBCE ३ for १. ४ P ब्रह्मइध्यौ ।. Cp ब्रह्मऽइध्यौ ।.

ग्रंसं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद् व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥ ५२ ॥

वेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म् । कृ॒त्वा । दक्षि॑णाम् ।
ग्रंस॑म् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽव॒त् । व॒र्षेण॑ । आज्ये॑न । रोहि॑तः ॥ ५२ ॥

व॒र्षमाज्यं॑ ग्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत ।
तत्रै॒तान् पर्व॑ताना॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ॥ ५३ ॥

व॒र्षम् । आज्य॑म् । ग्रं॒सः । अ॒ग्निः । वेदिः॑ । भूमिः॑ । अ॒क॒ल्प॒त ।
तत्र॑ । ए॒तान् । पर्व॑तान् । अ॒ग्निः । गीः॒ऽभिः । ऊ॒र्ध्वान् । अ॒क॒ल्प॒य॒त् ॥ ५३ ॥

गी॒र्भिरू॒र्ध्वान् क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत् ।
त्वयी॒दं सर्वं॑ जायतां॒ यद् भू॒तं यच्च॑ भा॒व्य॒म् ॥ ५४ ॥

गी॒ःऽभिः । ऊ॒र्ध्वान् । क॒ल्प॒यि॒त्वा । रोहि॑तः । भूमि॑म् । अ॒ब्र॒वी॒त् ।
त्वयि॑ । इ॒दम् । सर्व॑म् । जा॒य॒ता॒म् । यत् । भू॒तम् । यत् । च॒ । भा॒व्य॒म् ॥ ५४ ॥

स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत ।
तस्मा॑द्ध ज॒ज्ञ इ॒दं सर्वं॒ यत् किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥ ५५ ॥

सः । य॒ज्ञः । प्र॒थ॒मः । भू॒तः । भव्यः॑ । अ॒जा॒य॒त ।
तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरोच॑ते । रोहि॑तेन । ऋषि॑णा । आ॒ऽभृ॑तम् ॥ ५५ ॥

यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ् सूर्यं॑ च॒ मेह॑ति ।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोप॑रम् ॥ ५६ ॥

यः । च॒ । गाम् । प॒दा । स्फु॒रति॑ । प्र॒त्यङ् । सूर्य॑म् । च॒ । मेह॑ति ।
तस्य॑ । वृ॒श्चा॒मि॒ । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒वः॒ । अप॑रम् ॥ ५६ ॥

यो मा॑भिच्छा॒यम॒त्येषि॑ मां चा॒ग्निं चा॑न्त॒रा ।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोप॑रम् ॥ ५७ ॥

यः । मा॒ । अ॒भि॒ऽछा॒यम् । अ॒ति॒ऽएषि॑ । माम् । च॒ । अ॒ग्निम् । च॒ । अ॒न्त॒रा ।

---

१ P च॒कर॑ ।. २ D यच्च॒ भाव्य॑म्. ३ A B[h] D S[m] Cs यज्ञ. ४ P ऋषी॑णा ।. ५ K ॰त्येति॒.

तस्य॑ । वृ॒श्चामि॒ । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒व॑ः । अप॑रम् ॥ ५७ ॥

यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॒न्तरा॒य॑ति ।

दु॒ष्वप्न्यं॑ तस्मि॑ञ्छ॒मलं दु॒रि॒तानि॑ च मृज्महे ॥ ५८ ॥

यः । अ॒द्य । दे॒व॒ । सूर्य॒ । त्वाम् । च॒ । माम् । च॒ । अ॒न्त॒रा । अय॑ति ।

दुः॒ऽस्वप्न्य॑म् । तस्मि॑न् । शम॑लम् । दुः॒ऽइ॒तानि॑ । च॒ । मृ॒ज्म॒हे॒ ॥ ५८ ॥

मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑ः ।

मान्त स्थु॑र्नो॒ अरा॑तयः ॥ ५९ ॥

मा । प्र । गा॒म॑ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिन॑ः ।

मा । अ॒न्तः । स्थु॒ः । न॒ः । अरा॑तयः ॥ ५९ ॥

यो य॒ज्ञस्य॑ प्र॒साध॑नस्त॒न्तुर्दे॒वेष्वात॑तः ।

तमाहु॑तमशीमहि ॥ ६० ॥ (६)

यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तु॒ः । दे॒वेषु॑ । आऽत॑तः ।

तम् । आऽहु॑तम् । अ॒शी॒म॒हि॒ ॥ ६० ॥ (६)

प्रथमेनुवाके प्रथमं सूक्तम् ॥

इति प्रथमोनुवाकः ॥

"उदस्य केतवः" इति सवितृदेवताकम् ॥

याज्ञिका वक्ष्यमाणप्रकारेण विनियुञ्जन्ति ।

"उदस्य केतवः" इत्यनुवाकस्य सलिलगणे पाठः । अतस्तस्य गणप्रयुक्तो विनियोगो द्रष्टव्यः [१.५] ॥

तथा उपनयने आयुरभिवृद्ध्यर्थम् अनेनानुवाकेन माणवकस्त्रिकालम् आदित्यम् उपतिष्ठेत । सूत्रितं हि । "उदस्य केतवः [१३.२] मूर्धाहम् [१६.३] विषासहिम् [१७.१] इत्युद्यन्तम् उपतिष्ठते मध्यंदिनेऽस्तं यन्तम्" इति । कौ° ७.९ ॥

तथा चातुर्मास्ये साकमेधपर्वणि पित्र्येष्टौ जातायाम् आदित्योपस्थाने इदं विनियुक्तम् । तद् उक्तं वैताने । "प्राञ्चोभ्युत्क्रम्योदस केतव इत्यादित्यमुपतिष्ठन्ते" इति । वै° २.५ ॥

उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते ।

आ॒दि॒त्यस्य॑ नृ॒चक्ष॑सो॒ महि॑व्रतस्य मी॒ढुष॑ः ॥ १ ॥

उत् । अ॒स्य॒ । के॒तव॑ः । दि॒वि । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।

आ॒दि॒त्यस्य॑ । नृ॒ऽचक्ष॑सः । महि॑ऽव्रतस्य । मी॒ढुष॑ः ॥ १ ॥

---

१ P Cp क॒र॒वः ।. We with P[2] J. २ B दुःष्वप्न्यं. ३ B C D E R S[m] Cs मृज्महे. P P[2] J Cp मृ॒ज्म॒हे॒ ।. We with Dc. ४ P गा॒म ।. ५ A B E R Dc P[2] J मी॒ढुषः.

दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।
स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥ २ ॥

दिशाम् । प्रऽज्ञानाम् । स्वरयन्तम् । अर्चिषा । सुऽपक्षम् । आशुम् । पतयन्तम् । अर्णवे ।
स्तवाम । सूर्यम् । भुवनस्य । गोपाम् । यः । रश्मिऽभिः । दिशः । आऽभाति । सर्वाः ॥ २ ॥

यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
तदादित्य महि तत् ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥ ३ ॥

यत् । प्राङ् । प्रत्यङ् । स्वधया । यासि । शीभम् । नानारूपे इति नानाऽरूपे । अहनी इति । कर्षि । मायया ।
तत् । आदित्य । महि । तत् । ते । महि । श्रवः । यत् । एकः । विश्वम् । परि । भूम । जायसे ॥ ३ ॥

विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।
स्रुताद् यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥ ४ ॥

विपःऽचितम् । तरणिम् । भ्राजमानम् । वहन्ति । यम् । हरितः । सप्त । बह्वीः ।
स्रुतात् । यम् । अत्त्रिः । दिवम् । उत्ऽनिनाय । तम् । त्वा । पश्यन्ति । परिऽयान्तम् । आजिम् ॥ ४ ॥

मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गाँ अति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥ ५ ॥

मा । त्वा । दभन् । परिऽयान्तम् । आजिम् । स्वस्ति । दुःऽगान् । अति । याहि । शीभम् ।
दिवम् । च । सूर्य । पृथिवीम् । च । देवीम् । अहोरात्रे इति । विऽमिमानः । यत् । एषि ॥ ५ ॥

स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।
यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥ ६ ॥

स्वस्ति । ते । सूर्य । चरसे । रथाय । येन । उभौ । अन्तौ । परिऽयासि । सद्यः ।
यम् । ते । वहन्ति । हरितः । वहिष्ठाः । शतम् । अश्वाः । यदि । वा । सप्त । बह्वीः ॥ ६ ॥

---

१ K K[m] S[m] V प्रज्ञानं. Dc प्रज्ञानां changed to प्रज्ञानं. P[2] प्रऽज्ञानम् ।. २ P रश्मि° ।. ३ P भूम ।. ४ A B B[h] C D E K K[m] R S[m] V Dc P P[2] J Cp स्तुता°. But A B[h] E R S[m] P[2] may be स्रुता°. Cs स्रुता°. ५ B E °भावंतौ. ६ All our authorities have वहिष्ठाः.

सुखं सूर्य[1] रथमंशुमन्तं स्योनं सुवह्निमधि[2] तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः[3] शतमश्वा यदि वा सप्त बह्वीः ॥ ७ ॥

सुऽखम् । सूर्य[1] । रथम् । अंशुऽमन्तम् । स्योनम् । सुऽवह्निम् । अधि । तिष्ठ । वाजिनम् ।
यम् । ते । वहन्ति । हरितः । वहिष्ठाः । शतम् । अश्वाः । यदि । वा । सप्त । बह्वीः ॥ ७ ॥

सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
अमोचि शुक्रो रजसः परस्ताद् विधूय देवस्तमो दिवमारुहत् ॥ ८ ॥

सप्त । सूर्यः । हरितः । यातवे । रथे । हिरण्यऽत्वचसः । बृहतीः । अयुक्त ।
अमोचि । शुक्रः । रजसः । परस्तात् । विऽधूय । देवः । तमः । दिवम् । आ । अरुहत् ॥ ८ ॥

उत् केतुना बृहता देव आगन्नपावृक् तमोभि ज्योतिरश्रैत् ।
दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥ ९ ॥

उत् । केतुना । बृहता । देवः । आ । अगन् । अप[4] । अवृक्[5] । तमः । अभि । ज्योतिः ।
अश्रैत् ।
दिव्यः । सुऽपर्णः । सः । वीरः । वि । अख्यत् । अदितेः । पुत्रः । भुवनानि । विश्वा ॥ ९ ॥

उद्यन् रश्मीना[6] तनुषे विश्वा रूपाणि पुष्यसि ।
उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ (७)

उत्ऽयन् । रश्मीन् । आ । तनुषे । विश्वा । रूपाणि । पुष्यसि ।
उभा । समुद्रौ । क्रतुना । वि । भासि । सर्वान् । लोकान् । परिऽभूः । भ्राजमानः ॥ १० ॥ (७)

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोर्णवम्[7] ।
विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं[8] हरितो वहन्ति ॥ ११ ॥

पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीडन्तौ । परि । यातः । अर्णवम् ।
विश्वा । अन्यः । भुवना । विऽचष्टे । हैरण्यैः । अन्यम् । हरितः । वहन्ति ॥ ११ ॥

दिवि त्वात्त्रिरधारयत्[9] सूर्या[10] मासाय कर्तवे ।

---

१ A B C D E K K^m R S^m V Dc Cs सूर्य. P P^2 J सूर्यै ।. Cp सूर्यम् ।. The emendation made by Rw to सूर्य appears desirable. २ B^h सुवर्णमधि. ३ All our authorities have वहिष्ठाः. ४ P अपः ।. ५ P अवृक् ।. ६ B B^h S^m उद्यन्नश्मीना. ७ A B यातो अर्णवम्. ८ A B E °रण्यं. ९ B °धारयत्°. १० So we with all our authorities. See Rw.

स एषि सुधृतस्तपन् विश्वा भूतावचाकशत् ॥ १२ ॥

दिवि । त्वा । अत्रिः । अधारयत् । सूर्यं । मासाय । कर्तवे ।

सः । एषि । सुऽधृतः । तपन् । विश्वा । भूता । अवऽचाकशत् ॥ १२ ॥

उभावन्तौ समर्षसि वत्सः संमातराविव ।

नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥ १३ ॥

उभौ । अन्तौ । सम् । अर्षसि । वत्सः । संमातरौऽइव ।

ननु । एतत् । इतः । पुरा । ब्रह्म । देवाः । अमी इति । विदुः ॥ १३ ॥

यत् समुद्रमनु श्रितं तत् सिषासति सूर्यः ।

अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥ १४ ॥

यत् । समुद्रम् । अनु । श्रितम् । तत् । सिषासति । सूर्यः ।

अध्वा । अस्य । विऽततः । महान् । पूर्वः । च । अपरः । च । यः ॥ १४ ॥

तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।

तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥ १५ ॥

तम् । सम् । आप्नोति । जूतिऽभिः । ततः । न । अप । चिकित्सति ।

तेन । अमृतस्य । भक्षम् । देवानाम् । न । अव । रुन्धते ॥ १५ ॥

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।

दृशे विश्वाय सूर्यम् ॥ १६ ॥

उत् । ऊं इति । त्यम् । जातऽवेदसम् । देवम् । वहन्ति । केतवः ।

दृशे । विश्वाय । सूर्यम् ॥ १६ ॥

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।

सूराय विश्वचक्षसे ॥ १७ ॥

अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तुऽभिः ।

सूराय । विश्वऽचक्षसे ॥ १७ ॥

अदृश्रन्नस्य केतवो वि रश्मयो जनाँ अनु ।

---

१ P P̊ J Cp सूर्यो ।. २ A १ for ३. ३ P विदुः ।. ४ E R जनें.

भ्राजन्तो अग्नयो यथा ॥ १८ ॥

अदृश्रन् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु ।

भ्राजन्तः । अग्नयः । यथा ॥ १८ ॥

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।

विश्वमा भासि रोचन ॥ १९ ॥

तरणिः । विश्वऽदर्शतः । ज्योतिःऽकृत् । असि । सूर्य ।

विश्वम् । आ । भासि । रोचन ॥ १९ ॥

प्रत्यङ् देवाना विशः प्रत्यङ्ङुदेषि मानुषीः ।

प्रत्यङ् विश्वं स्वर्दृशे ॥ २० ॥ (८)

प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् । उत् । एषि । मानुषीः ।

प्रत्यङ् । विश्वम् । स्वः । दृशे ॥ २० ॥ (८)

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।

त्वं वरुण पश्यसि ॥ २१ ॥

येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् । अनु ।

त्वम् । वरुण । पश्यसि ॥ २१ ॥

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।

पश्यन् जन्मानि सूर्य ॥ २२ ॥

वि । द्याम् । एषि । रजः । पृथु । अहः । मिमानः । अक्तुऽभिः ।

पश्यन् । जन्मानि । सूर्य ॥ २२ ॥

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।

शोचिष्केशं विचक्षणम् ॥ २३ ॥

सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य ।

शोचिःऽकेशम् । विऽचक्षणम् ॥ २३ ॥

---

१ B B[h] C D E Cs ज्योतिःकृदसि. २ B[h] C D E R S[m] प्रत्यङुदेषि. K[m] °गुदेषि. We with V Dc Cs. ३ E R जनँ. ४ A E K R Dc पश्यं. ५ A B D S[m] Cs शोचिःकेशं

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः।
ताभिर्याति स्वयुक्तिभिः ॥ २४ ॥

अयुक्त। सप्त। शुन्ध्युवः। सूरः। रथस्य। नप्त्यः।
ताभिः। याति। स्वयुक्तिऽभिः ॥ २४ ॥

रोहितो दिवमारुहत् तपसा तपस्वी।
स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥ २५ ॥

रोहितः। दिवम्। आ। अरुहत्। तपसा। तपस्वी।
सः। योनिम्। आ। एति। सः। ऊं इति। जायते। पुनः। सः। देवानाम्। अधिऽपतिः।
बभूव ॥ २५ ॥

यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः।
सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी[1] जनयन् देव एकः ॥ २६ ॥

यः। विश्वऽचर्षणिः। उत। विश्वतःऽमुखः। यः। विश्वतःऽपाणिः। उत। विश्वतःऽपृथः।
सम्। बाहुऽभ्याम्। भरति। सम्। पतत्रैः। द्यावापृथिवी इति। जनयन्। देवः। एकः ॥ २६ ॥

एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादमभ्येति पश्चात्।
द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं१[2] समासते ॥ २७ ॥

एकऽपात्। द्विऽपदः। भूयः। वि। चक्रमे। द्विऽपात्। त्रिऽपादम्। अभि। एति। पश्चात्।
द्विऽपात्। ह। षट्ऽपदः। भूयः। वि। चक्रमे। ते। एकऽपदः। तन्वम्। सम्। आसते ॥ २७ ॥

अतन्द्रो यास्यन् हरितो यदास्थाद्[3] द्वे रूपे कृणुते रोचमानः।
केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥ २८ ॥

अतन्द्रः। यास्यन्। हरितः। यत्। आऽअस्थात्। द्वे इति। रूपे इति। कृणुते। रोचमानः।
केतुऽमान्। उत्ऽयन्। सहमानः। रजांसि। विश्वाः। आदित्य। प्रऽवतः। वि। भासि ॥ २८ ॥

बण्महाँ[4] असि सूर्य बडादित्य महाँ[5] असि।
महांस्ते महतो महिमा त्वमादित्य महाँ असि ॥ २९ ॥

वट्। महान्। असि। सूर्य। बट्। आदित्य। महान्। असि।
महान्। ते। महतः। महिमा। त्वम्। आदित्य। महान्। असि ॥ २९ ॥

---

१ R ॰पृथिवी. २ A B B^{h} C E ३ for १. ३ R ॰स्थान्द्वे. ४ E R बण्महैं. ५ E महैं.

रोचसे दिवि रोचसे[1] अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्व[2]१न्तः ।
उभा समुद्रौ रुच्या व्यापिथ[3] देवो देवासि महिषः स्वर्जित् ॥ ३० ॥ (९)

रोचसे । दिवि । रोचसे । अन्तरिक्षे । पतङ्ग । पृथिव्याम् । रोचसे । रोचसे । अप्ऽसु । अन्तः ।
उभा । समुद्रौ । रुच्या । वि । आपिथ । देवः । देव । असि । महिषः । स्वःऽजित् ॥ ३० ॥ (९)

अर्वाङ् परस्तात् प्रयतो व्यध्व आशुर्विपश्चित् पतयन् पतङ्गः ।
विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत् ॥ ३१ ॥

अर्वाङ् । परस्तात् । प्रऽयतः । विऽअध्वे । आशुः । विपःऽचित् । पतयन् । पतङ्गः ।
विष्णुः । विऽचित्तः । शवसा । अधिऽतिष्ठन् । प्र । केतुना । सहते । विश्वम् । एजत् ॥ ३१ ॥

चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥ ३२ ॥

चित्रः । चिकित्वान् । महिषः । सुऽपर्णः । आऽरोचयन् । रोदसी इति । अन्तरिक्षम् ।
अहोरात्रे इति । परि । सूर्यम् । वसाने इति । प्र । अस्य । विश्वा । तिरतः । वीर्याणि ॥ ३२ ॥

तिग्मो विभ्राजन् तन्व[4]१ं शिशानो[5]रंगमासः प्रवतो रराणः ।
ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्[6] प्रदिशः कल्पमानः ॥ ३३ ॥

तिग्मः । विऽभ्राजन् । तन्वम् । शिशानः । अरम्ऽगमासः । प्रऽवतः । रराणः ।
ज्योतिष्मान् । पक्षी । महिषः । वयःऽधाः । विश्वाः । आ । अस्थात् । प्रऽदिशः । कल्पमानः ॥ ३३ ॥

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
दिवाकरोति द्युम्नैस्तमांसि विश्वातारीद् दुरितानि शुक्रः ॥ ३४ ॥

चित्रम् । देवानाम् । केतुः । अनीकम् । ज्योतिष्मान् । प्रऽदिशः । सूर्यः । उत्ऽयन् ।
दिवाऽकरः । अति । द्युम्नैः । तमांसि । विश्वा । अतारीत् । दुःऽइतानि । शुक्रः ॥ ३४ ॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।

---

१ R दिवि रोचसे. २ A $\mathrm{B^h}$ C E R ३ for १. ३ D E Cs व्यापिथ. ४ B $\mathrm{B^h}$ C D E $\mathrm{S^m}$ Cs ३ for १. We with K $\mathrm{K^m}$ R V Dc. ५ $\mathrm{B^h}$ °नोअरंग°. ६ B Cs अस्थात्.

आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ३५ ॥

चित्रम्। देवानाम्। उत्। अगात्। अनीकम्। चक्षुः। मित्रस्य। वरुणस्य। अग्नेः।
आ। अप्रात्। द्यावापृथिवी इति। अन्तरिक्षम्। सूर्यः। आत्मा। जगतः। तस्थुषः। च ॥ ३५ ॥

उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्।
पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥ ३६ ॥

उच्चा। पतन्तम्। अरुणम्। सुऽपर्णम्। मध्ये। दिवः। तरणिम्। भ्राजमानम्।
पश्याम। त्वा। सवितारम्। यम्। आहुः। अजस्रम्। ज्योतिः। यत्। अविन्दत्। अत्रिः ॥ ३६ ॥

दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः।
स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥ ३७ ॥

दिवः। पृष्ठे। धावमानम्। सुऽपर्णम्। अदित्याः। पुत्रम्। नाथऽकामः। उप। यामि। भीतः।
सः। नः। सूर्य। प्र। तिर। दीर्घम्। आयुः। मा। रिषाम। सुऽमतौ। ते। स्याम ॥ ३७ ॥

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्।
स देवान्त्सर्वानुरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥ ३८ ॥

सहस्रऽअह्न्यम्। विऽयतौ। अस्य। पक्षौ। हरेः। हंसस्य। पततः। स्वःऽगम्।
सः। देवान्। सर्वान्। उरसि। उपऽदद्य। सम्ऽपश्यन्। याति। भुवनानि। विश्वा ॥ ३८ ॥

रोहितः कालो अभवद् रोहितोग्रे प्रजापतिः।
रोहितो यज्ञानां मुखं रोहितः[3] स्व१राभरत्[4] ॥ ३९ ॥

रोहितः। कालः। अभवत्। रोहितः। अग्रे। प्रजाऽपतिः।
रोहितः। यज्ञानाम्। मुखम्। रोहितः। स्वः। आ। अभरत्[6] ॥ ३९ ॥

रोहितो लोको अभवद् रोहितोत्यतपद् दिवम्।
रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥ ४० ॥ (१०)

रोहितः। लोकः। अभवत्। रोहितः। अति। अतपत्। दिवम्।
रोहितः। रश्मिऽभिः। भूमिम्। समुद्रम्। अनु। सम्। चरत् ॥ ४० ॥ (१०)

---

१ P उत्। २ P आदित्याः। ३ A D E K K^m S^m रोहित for रोहितः. ४ A B^h C D E S^m Cs ३ for १. We with B K K^m V Dc. ५ R ॰भरन्. ६ P अभवत्।

सर्वा दिशः समचरद् रोहितोधिपतिर्दिवः ।
दिवं समुद्रमाद् भूमिं सर्वं भूतं वि रक्षति ॥ ४१ ॥

सर्वाः । दिशः । सम् । अचरत् । रोहितः । अधिऽपतिः । दिवः ।
दिवम् । समुद्रम् । आत् । भूमिम् । सर्वम् । भूतम् । वि । रक्षति ॥ ४१ ॥

आरोहञ्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।[1]
चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकानभि यद् वि-
भाति ॥ ४२ ॥

आऽरोहन् । शुक्रः । बृहतीः । अतन्द्रः । द्वे इति । रूपे इति । कृणुते । रोचमानः ।
चित्रः । चिकित्वान् । महिषः । वातम्ऽआयाः । यावतः । लोकान् । अभि । यत् ।
विऽभाति ॥ ४२ ॥

अभ्य१न्यदेति पर्यन्यदस्यतेहोरात्राभ्यां महिषः कल्पमानः ।[2][3][4]
सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥ ४३ ॥

अभि । अन्यत् । एति । परि । अन्यत् । अस्यते । अहोरात्राभ्याम् । महिषः । कल्पमानः ।
सूर्यम् । वयम् । रजसि । क्षियन्तम् । गातुऽविदम् । हवामहे । नाधमानाः ॥ ४३ ॥

पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।[5]
विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥ ४४ ॥[6]

पृथिवीऽप्रः । महिषः । नाधमानस्य । गातुः । अदब्धऽचक्षुः । परि । विश्वम् । बभूव ।
विश्वम् । सम्ऽपश्यन् । सुऽविदत्रः । यजत्रः । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥ ४४ ॥

पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।
सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥ ४५ ॥

---

१ A $\overset{h}{B}$ C E R Dc आरोहंछुक्रो. $\overset{m}{K}$ °हंच्छु°. Cs °हंन्छु°. We with D K $\overset{m}{S}$ V. $\overset{2}{P}$ °रोहंम् ।. २ K $\overset{m}{K}$ अभ्या३°. A $\overset{h}{B}$ C D E R $\overset{m}{S}$ Dc Cs अभ्य३°. We with V. ३ $\overset{m}{K}$ °देति. K V °देति. $\overset{2}{P}$ एति ।. We with A $\overset{h}{B}$ C D E R $\overset{m}{S}$ Dc Cs P J Cp. ४ A °ते अहो°. ५ So we with A B $\overset{h}{B}$ C D E R $\overset{m}{S}$ Cs P J Cp. Also Rw. K $\overset{m}{K}$ V Dc $\overset{2}{P}$ बभूव. We have probably to understand a यः with बभूव. ६ $\overset{h}{B}$ E ब्रवीमि.

परि॑ । अ॒स्य । म॒हि॒मा । पृ॒थि॒वीम् । स॒मु॒द्रम् । ज्योति॑षा । वि॒ऽभ्राज॑न् । परि॑ । द्याम् । अ॒न्तरि॑क्षम् ।
सर्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्रः॑ । यज॑त्रः । इ॒दम् । शृ॒णो॒तु । यत् । अ॒हम् । ब्रवी॑मि ॥ ४५ ॥

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।
य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥ ४६ ॥ (११)

अबो॑धि । अ॒ग्निः । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म् ।
य॒ह्वाःऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑नाः । प्र । भा॒नवः॑ । सि॒स्र॒ते । नाक॑म् । अच्छ॑ ॥ ४६ ॥ (११)

द्वितीयेनुवाके प्रथमं सूक्तम् ॥

इति द्वितीयोनुवाकः ॥

रोहितदेवताकम् एतत् सूक्तम् । रोहितः कश्चिद् देव उद्यत्सूर्यरूपः सूर्यस्य रोहितनामको यः प्रधानोश्वस्तद्रूपेण वा कल्पितः । तस्य परमार्थं रूपं त्रयोदशचतुर्दशपञ्चदशषोडशसप्तदशाष्टादशैकोनविंशेषु मन्त्रेषु द्रष्टव्यम् ॥

सांप्रदायिकास्तु एवं विनियुञ्जन्ति । तद्यथा ।

आभिचारिके कर्मणि "य इमे द्यावापृथिवी" इत्यनुवाकेन पाशान् पदे वृश्चति विधानेन ॥

तथा तत्रैव कर्मणि अनेनानुवाकेन रक्तशालिक्षीरौदनं संपात्याभिमन्त्र्य द्वेष्याय ददाति ॥

तस्मिन्नेव कर्मणि अनेनानुवाकेन आमपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति ॥

तथा तस्मिन्नेव कर्मणि अनेनानुवाकेन वृषभं संपातवन्तं कृत्वा शत्रोरभिमुखं विसृजति ॥

तथा उक्त एव कर्मणि अनेनानुवाकेन शत्रुप्रतिकृतिं मृन्मयीं कृत्वा पश्चाद् अग्नेः स्थाणौ बद्ध्वा तस्या मूर्ध्नि संपातान् आनयति ॥ "यस्मिन् षडुर्वीः पञ्च" [६] इत्यृचा उदवज्रान् प्रहरति उक्तेन विधानेन ॥ "यो अन्नादो अन्नपतिः" [७] इत्यृचा उदकम् अभिमन्त्र्य द्वेष्यं मनसा चाध्यायन्नाचामति ॥

तद् उक्तं कौशिकेन । "समिद्धो अग्निः [१३. १. २८–३२] य इमे द्यावापृथिवी [१३. ३] अजैष्म [१६. ६] इत्य-
"धिपाशान् आदधाति । पदेपदे पाशान् वृश्चति । अधिपाशान् बाधकां छङ्कूंस्तान् संक्षुद्य संनह्य भ्राष्ट्रेभ्यस्यति । अशिशिषोः क्षी-
"रौदनादीनि त्रीणि । गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातान् अभ्यातिनयति । षष्ठ्योदवज्रान् प्रहरति ।
"सप्तम्याचामति" इति [कौ° ६. ३] ॥

य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रा॒पिं कृ॒त्वा भुव॑नानि॒ वस्ते॑ ।
यस्मि॑न् क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः॒ पत॒ङ्गो अनु॑ वि॒चाक॑शीति[३]
तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ ।
उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पा॒शान् ॥ १ ॥

यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ । यः । द्रा॒पिम् । कृ॒त्वा । भुव॑नानि । वस्ते॑ ।

---

१ P has स॒म् ।. २ P उ॒षास॑म् ।. ३ The division into avasânas which we adopt in this and the following verses is based on A B B[h] C D E K K[m] R S[m] V Dc Cs P P[2] J. See Rw.

यस्मिन् । क्षियन्ति । प्रऽदिशः । षट् । उर्वीः । याः । पतङ्गः । अनु । विऽचाकशीति ।
तस्य । देवस्य ॥ क्रुद्धस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति ।
उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥ १ ॥

यस्माद् वाता ऋतुथा पवन्ते यस्मात् समुद्रा अधि विक्षरन्ति
तस्य देवस्य ।०।० ॥ २ ॥

यस्मात् । वाताः[1] । ऋतुऽथा । पवन्ते । यस्मात् । समुद्राः । अधि । विऽक्षरन्ति ।
तस्य ।० ॥ २ ॥

यो मारयति प्राणयति यस्मात् प्राणन्ति भुवनानि विश्वा
तस्य०।०।० ॥ ३ ॥

यः । मारयति । प्राणयति । यस्मात् । प्राणन्ति । भुवनानि । विश्वा ।
तस्य ।० ॥ ३ ॥

यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति
तस्य०।०।० ॥ ४ ॥

यः । प्राणेन । द्यावापृथिवी इति । तर्पयति । अपानेन । समुद्रस्य । जठरम् । यः । पिपर्ति ।
तस्य ।० ॥ ४ ॥

यस्मिन् विराट् परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।
यः परस्य प्राणं परमस्य तेज आददे
तस्य०।०।० ॥ ५ ॥

यस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपतिः । अग्निः । वैश्वानरः । सह । पङ्क्त्या । श्रितः ।
यः । परस्य । प्राणम् । परमस्य । तेजः । आऽददे ।
तस्य ।० ॥ ५ ॥

यस्मिन् षडुर्वीः पञ्च दिशो अधि श्रिताश्चतस्र आपो यज्ञस्य त्रयोक्षराः ।
यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत
तस्य०।०।० ॥ ६ ॥

यस्मिन् । षट् । उर्वीः । पञ्च । दिशः । अधि । श्रिताः । चतस्रः । आपः । यज्ञस्य । त्रयः ।
अक्षराः[2] ।

---

१ P वातः ।. २ All our authorities read त्रयोक्षरा ।.

यः । अन्तरा । रोदसी इति । क्रुद्धः । चक्षुषा[1] । ऐक्षत ।
तस्य ।० ॥ ६ ॥

यो [2]अन्नादो [3]अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।
भूतो भविष्यद् भुवनस्य यस्पतिस्-
तस्य०।०।० ॥ ७ ॥

यः । अन्नऽअदः[4] । अन्नऽपतिः । बभूव । ब्रह्मणः । पतिः । उत । यः ।
भूतः । भविष्यत् । भुवनस्य । यः । पतिः ।
तस्य ।० ॥ ७ ॥

अहोरात्रैर्वि[6]मितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते
तस्य०।०।० ॥ ८ ॥

अहोरात्रैः । विऽमितम् । त्रिंशत्ऽअङ्गम् । त्रयःऽदशम् । मासम् । यः । निःऽमिमीते ।
तस्य ।० ॥ ८ ॥

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत् पतन्ति ।
त आववृत्रन्त्सदनादृतस्य
तस्य०।०।० ॥ ९ ॥

कृष्णम् । निऽयानम् । हरयः । सुऽपर्णाः । अपः । वसानाः । दिवम् । उत् । पतन्ति ।
ते । आ । अववृत्रन् । सदनात् । ऋतस्य ।
तस्य ।० ॥ ९ ॥

यत् ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु ।
यस्मिन्त्सूर्या आर्पिताः सप्त साकं
तस्य०।०।० ॥ १० ॥ (१२)

यत् । ते । चन्द्रम् । कश्यप । रोचनऽवत् । यत् । सम्ऽहितम् । पुष्कलम् । चित्रऽभानु ।
यस्मिन् । सूर्याः । आर्पिताः । सप्त । साकम् ।
तस्य ।० ॥ १० ॥ (१२)

---

१ J चक्षुंषा । changed to चक्षुषा ।. P[2] चक्षुषा ।. We with P Cp. २ A योन्नादो. ३ B K K̄[m] R V Dc omit अ॰. ४ P ॰अदः ।. ५ P अन्नऽपतिः ।. ६ K ॰र्नि॰. ७ P निःऽमिमी॰ ।. ८ K पुंष्कुरं. P पुष्कलम् ।.

बृहदेनमनु वस्ते पुरस्ताद् रथंतरं प्रति गृह्णाति पश्चात् ।
ज्योतिर्वसाने सदमप्रमादं
तस्य०।०।० ॥ ११ ॥

बृहत् । एनम् । अनु । वस्ते । पुरस्तात् । रथम्ऽतरम् । प्रति । गृह्णाति । पश्चात् ।
ज्योतिः । वसाने इति । सदम् । अप्रऽमादम् ।
तस्य ।० ॥ ११ ॥

बृहदन्यतः पक्ष आसीद् रथंतरमन्यतः सबले सध्रीची ।
यद् रोहितमजनयन्त देवास्-
तस्य०।०।० ॥ १२ ॥

बृहत् । अन्यतः । पक्षः । आसीत् । रथम्ऽतरम् । अन्यतः । सबले इति सऽबले । सध्रीची इति ।
यत् । रोहितम् । अजनयन्त । देवाः ।
तस्य ।० ॥ १२ ॥

स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।
स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवं
तस्य०।०।० ॥ १३ ॥

सः । वरुणः । सायम् । अग्निः । भवति । सः । मित्रः । भवति । प्रातः । उत्ऽयन् ।
सः । सविता । भूत्वा । अन्तरिक्षेण । याति । यः । इन्द्रः । भूत्वा । तपति । मध्यतः । दिवम् ।
तस्य ।० ॥ १३ ॥

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वानुरस्युपदद्य संपश्यन् याति भुवनानि विश्वा
तस्य०।०।० ॥ १४ ॥

सहस्रऽअह्न्यम् । विऽयतौ । अस्य । पक्षौ । हरेः । हंसस्य । पततः । स्वःऽगम् ।
सः । देवान् । सर्वान् । उरसि । उपऽदद्य । सम्ऽपश्यन् । याति । भुवनानि । विश्वा ।
तस्य ।० ॥ १४ ॥

अयं स देवो अप्स्व[1]न्तः सहस्रमूलः पुरुशाको अद्भिः[2] ।
य इदं विश्वं भुवनं जजान
तस्य॰।०।० ॥ १५ ॥

अयम् । सः । देवः । अप्ऽसु । अन्तः । सहस्रऽमूलैः[3] । पुरुऽशाकः । अद्भिः ।
यः । इदम् । विश्वम् । भुवनम् । जजान ।
तस्य ।० ॥ १५ ॥

शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।
यस्योर्ध्वा दिवं तन्व[4]स्तपन्त्यर्वाङ् सुवर्णैः पटरैर्वि भाति
तस्य॰।०।० ॥ १६ ॥

शुक्रम् । वहन्ति । हरयः । रघुऽस्यदः । देवम् । दिवि । वर्चसा । भ्राजमानम् ।
यस्य । ऊर्ध्वाः । दिवम् । तन्वः । तपन्ति । अर्वाङ् । सुऽवर्णैः । पटरैः । वि । भाति ।
तस्य ।० ॥ १६ ॥

येनादित्यान् हरितः संवहन्ति येन यज्ञेन बहवो यन्ति[5] प्रजानन्तः ।
यदेकं ज्योतिर्बहुधा विभाति[6]
तस्य॰।०।० ॥ १७ ॥

येन । आदित्यान् । हरितः । सम्ऽवहन्ति । येन । यज्ञेन । बहवः । यन्ति । प्रऽजानन्तः ।
यत् । एकम् । ज्योतिः । बहुऽधा । विऽभाति[6] ।
तस्य ।० ॥ १७ ॥

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुस्-
तस्य॰।०।० ॥ १८ ॥

सप्त । युञ्जन्ति । रथम् । एकऽचक्रम् । एकः । अश्वः । वहति । सप्तऽनामा ।

---

१ A B[h] C E R ३ for १. We with D K K[m] S[m] V Dc Cs. २ K K[m] V Dc अद्रिः. ३ P ॰मूलम् ।. ४ The MSS. read thus: K K[m] V ॰न्वा१॰; D ॰न्व१॰; Dc ॰न्वा३॰ changed to ॰न्व१/२॰; E Cs तन्वा१त॰; C तन्वा३स्त॰; R तन्वा३स्त॰; S[m] तन्वास्त॰. ५ S[m] यांति. ६ All our authorities read विभाति except P[2] which has विऽभाति and which we follow.

त्रिऽनाभि । चक्रम् । अजरम् । अनर्वम् । यत्र । इमा । विश्वा । भुवना । अधि । तस्थुः ।
तस्य ।० ॥ १८ ॥

अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।
ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा
तस्य०।०।० ॥ १९ ॥

अष्टऽधा । युक्तः । वहति । वह्निः । उग्रः । पिता । देवानाम् । जनिता । मतीनाम् । ऋतस्य । तन्तुम् । मनसा । मिमानः । सर्वाः । दिशः । पवते । मातरिश्वा ।
तस्य ।० ॥ १९ ॥

सम्यञ्चं तन्तुं प्रदिशो[१]ऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे
तस्य०।०।० ॥ २० ॥ (१३)

सम्यञ्चम् । तन्तुम् । प्रऽदिशः । अनु । सर्वाः । अन्तः । गायत्र्याम्[२] । अमृतस्य । गर्भे ।
तस्य ।० ॥ २० ॥ (१३)

निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।
विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि[३] विद्म
तस्य०।०।० ॥ २१ ॥

[४]निऽम्रुचः । तिस्रः । विऽउषः । ह । तिस्रः । त्रीणि । रजांसि । दिवः[५] । अङ्ग । तिस्रः ।
विद्म । ते । अग्ने । त्रेधा । जनित्रम् । त्रेधा । देवानाम् । जनिमानि । विद्म ।
तस्य ।० ॥ २१ ॥

वि य और्णोत् पृथिवीं जायमान आ समुद्रमदधादन्तरिक्षे
तस्य०।०।० ॥ २२ ॥

वि । यः । और्णोत् । पृथिवीम् । जायमानः । आ । समुद्रम् । अदधात् । अन्तरिक्षे ।
तस्य ।० ॥ २२ ॥

त्वमग्ने क्रतुभिः केतुभिर्हितो[६]३र्कः समिद्ध उदरोचथा दिवि ।

---

१ B D प्रदिशो°. २ P गायत्र्यम् ।. ३ A S^m जनिमानि. ४ P निम्रुचः ।. ५ P दिवः ।.
६ A D S^m V Cs १ for ३. We with B^h C E K K^m Dc.

किमभ्यार्चन्मरुतः पृश्निमातरो यद् रोहितमजनयन्त देवास्-
तस्य॰।॰।॰ ॥ २३ ॥

त्वम् । अग्ने । क्रतुऽभिः । केतुऽभिः । हितः । अर्कः । सम्ऽइद्धः । उत् । अरोचथाः । दिवि ।
किम् । अभि । आर्चन् । मरुतः । पृश्निऽमातरः । यत् । रोहितम् । अजनयन्त । देवाः ।
तस्य ।॰ ॥ २३ ॥

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
योऽ३स्येशे द्विपदो यश्चतुष्पदस्-
तस्य॰।॰।॰ ॥ २४ ॥

यः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः ।
यः । अस्य । ईशे । द्विऽपदः । यः । चतुःऽपदः ।
तस्य ।॰ ॥ २४ ॥

एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादमभ्येति पश्चात् ।
चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानस्-
तस्य देवस्य । क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ २५ ॥

एकऽपात् । द्विऽपदः । भूयः । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् ।
चतुःपात् । चक्रे । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तिम् । उपऽतिष्ठमानः ।
तस्य । देवस्य ॥ क्रुद्धस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति ।
उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥ २५ ॥

कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।
स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥ २६ ॥ (१४)

कृष्णायाः । पुत्रः । अर्जुनः । रात्र्याः । वत्सः । अजायत ।
सः । ह । द्याम् । अधि । रोहति । रुहः । रुरोह । रोहितः ॥ २६ ॥ (१४)

तृतीयेऽनुवाके प्रथमं सूक्तम् ॥

इति तृतीयोऽनुवाकः ॥

---

१ K K^m V Dc १ for ३. Cs has no kampa. We with B^h E. २ R ॰मभिस्वरे.

एतदपि रोहितदेवताकम् । विनियोगस्तु "स एति" इत्यनुवाकं जपति स्वर्गकाम इति विनियोगमालायाम् ॥

स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत् ॥ १ ॥

सः । एति । सविता । स्वः । दिवः । पृष्ठे । अवऽचाकशत् ॥ १ ॥

रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥ २ ॥

रश्मिऽभिः । नभः । आऽभृतम् । महाऽइन्द्रः । एति । आऽवृतः ॥ २ ॥

स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ।० ॥ ३ ॥

सः । धाता । सः । विऽधर्ता । सः । वायुः । नभः । उत्ऽश्रितम् ।० ॥ ३ ॥

सोऽर्यमा स वरुणः स रुद्रः स महादेवः ।० ॥ ४ ॥

सः । अर्यमा । सः । वरुणः । सः । रुद्रः । सः । महाऽदेवः ।० ॥ ४ ॥

सो अग्निः स उ सूर्यः स उ एव महायमः ।० ॥ ५ ॥

सः । अग्निः । सः । ऊं इति । सूर्यः । सः । ऊं इति । एव । महाऽयमः ।० ॥ ५ ॥

तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ।० ॥ ६ ॥

तम् । वत्साः । उप । तिष्ठन्ति । एकऽशीर्षाणः । युताः । दश ।० ॥ ६ ॥

पश्चात् प्राञ्च आ तन्वन्ति यदुदेति वि भासति ।० ॥ ७ ॥

पश्चात् । प्राञ्चः । आ । तन्वन्ति । यत् । उत्ऽएति । वि । भासति ।० ॥ ७ ॥

तस्यैष मारुतो गणः स एति शिक्याकृतः ॥ ८ ॥

तस्य । एषः । मारुतः । गणः । सः । एति । शिक्याऽकृतः ॥ ८ ॥

रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥ ९ ॥

रश्मिऽभिः । नभः । आऽभृतम् । महाऽइन्द्रः । एति । आऽवृतः ॥ ९ ॥

तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥ १० ॥

तस्य । इमे । नव । कोशाः । विष्टम्भाः । नवऽधा । हिताः ॥ १० ॥

---

१ K स्वर्दिवः पृ°. २ A B B^h C D E K^m R V Dc Cs °स्पृष्ठेव°. K °वः पृष्ठेव°. We with S^m. ३ S^m उच्छृतं. ४ The Vaidikas repeat the line रश्मिभिर्नभ आभृतं &c. after verses 3, 4, 5, 6 and 7. D S^m and Dc support the repetition and the other MSS. are not opposed to it, as their omission of indisputable intermediate repetition is habitual.

स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥ ११ ॥

सः । प्रऽजाभ्यः । वि । पश्यति । यत् । च । प्राणति । यत् । च । न ॥ ११ ॥

तमिदं निगतं सहः स एष एक एकवृदेक एव ॥ १२ ॥

तम् । इदम् । निऽगतम् । सहः । सः । एषः । एकः । एकऽवृत् । एकः । एव ॥ १२ ॥

एते अस्मिन् देवा एकवृतो भवन्ति ॥ १३ ॥ (१५)

एते । अस्मिन् । देवाः । एकऽवृतः । भवन्ति ॥ १३ ॥ (१५)

इति चतुर्थेनुवाके प्रथमं पर्यायसूक्तम् ॥

कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥ १ ॥

कीर्तिः । च । यशः । च । अम्भः । च । नभः । च । ब्राह्मणऽवर्चसम् । च । अन्नम् । च । अन्नऽअद्यम् । च ॥ १ ॥

य एतं देवमेकवृतं वेद ॥ २ ॥

यः । एतम् । देवम् । एकऽवृतम् । वेद ॥ २ ॥

न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ।०[१] ॥ ३ ॥

न । द्वितीयः । न । तृतीयः । चतुर्थः । न । अपि । उच्यते ।० ॥ ३ ॥

न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ।० ॥ ४ ॥

न । पञ्चमः । न । षष्ठः । सप्तमः । न ।० ॥ ४ ॥

नाष्टमो[२] न नवमो दशमो नाप्युच्यते ।० ॥ ५ ॥

न । अष्टमः । न । नवमः । दशमः । न । अपि । उच्यते ।० ॥ ५ ॥

स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ।० ॥ ६ ॥

सः । सर्वस्मै । वि । पश्यति । यत् । च । प्राणति । यत् । च । न ।० ॥ ६ ॥

तमिदं निगतं सहः स एष एक एकवृदेक एव ।० ॥ ७ ॥

तम् । इदम् । निऽगतम् । सहः । सः । एषः । एकः । एकऽवृत् । एकः । एव ।० ॥ ७ ॥

---

१ The Vaidikas repeat य एतं देवमेकवृतं वेद after the following verses of this and the first verse of the next paryâya-sûkta. **D** and **S̊** support the repetition, and the other MSS. are not opposed to it, as they invariably omit all intermediate repetitions. २ **K K̊ R V D**c नाष्टमो. We with **A B B̊ C D E S̊ C**s.

सर्वे॑ अस्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति ।० ॥ ८ ॥ (१६)

सर्वे॑ । अ॒स्मि॒न् । दे॒वाः । ए॒क॒ऽवृ॒तः । भ॒व॒न्ति ।० ॥ ८ ॥ (१६)

इति चतुर्थेनुवाके द्वितीयं पर्यायसूक्तम् ॥

ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒-न्नाद्यं॑ च ।० ॥ १ ॥

ब्रह्म॑ । च॒ । तपः॑ । च॒ । की॒र्तिः॑ । च॒ । यशः॑ । च॒ । अम्भः॑ । च॒ । नभः॑ । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒-सम् । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ ।० ॥ १ ॥

भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥ २ ॥

भू॒तम् । च॒ । भव्य॑म् । च॒ । श्र॒द्धा । च॒ । रुचिः॑ । च॒ । स्वः॒ऽगः । च॒ । स्व॒धा । च॒ ॥ २ ॥

य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥ ३ ॥

यः । ए॒तम् । दे॒वम् । ए॒क॒ऽवृत॑म् । वेद॑ ॥ ३ ॥

स ए॒व मृ॒त्युः सो॒३॑मृतं॒ सो॒३॑भ्वं॑ स रक्षः॑ ॥ ४ ॥

सः । ए॒व । मृ॒त्युः । सः । अ॒मृत॑म् । सः । अ॒भ्व॒म् । सः । रक्षः॑ ॥ ४ ॥

स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोनु॒ संहि॑तः ॥ ५ ॥

सः । रु॒द्रः । व॒सु॒ऽवनिः॑ । व॒सु॒ऽदेये॑ । न॒मः॒ऽवा॒के । व॒ष॒ट्ऽका॒रः । अनु॑ । सम्ऽहि॑तः ॥ ५ ॥

तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥ ६ ॥

तस्य॑ । इ॒मे । सर्वे॑ । या॒तवः॑ । उप॑ । प्र॒ऽशिष॑म् । आ॒स॒ते ॥ ६ ॥

तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ॥ ७ ॥ (१७)

तस्य॑ । अ॒मू । सर्वाः॑ । नक्ष॑त्रा । वशे॑ । च॒न्द्रम॑सा । स॒ह ॥ ७ ॥ (१७)

इति चतुर्थेनुवाके तृतीयं पर्यायसूक्तम् ॥

---

१ All our authorities have सर्वे अस्मिन्देवा, except P² which has सर्वे॑ ।. २ K^m चं भव्यं॑ च. B B^h D E K R S^m Cs चं भव्यं चं. P Cp भव्यम् ।. J भव्य॑म् changed to भ॒व्यम् ।. We with A C V Dc P². ३ P J insert सर्व॑म् । च॒ । after भव्य॑म् । च॒ ।. Also P² but without accents. The Saṁhitâ MSS. (A B B^h C D E K K^m S^m) and Cp omit the words. R Dc once read them (without accents) but have subsequently cancelled them. ४ A °भ्वां ३. B^h C D E R S^m Cs °भ्वं ३. We with K K^m V Dc. ५ P P² J °वने॑ ।. We with Cp. ६ P प्रऽशि॑षम् ।.

स वा अह्नोऽजायत तस्मादहरजायत ॥ १ ॥

सः । वै । अह्नः । अजायत । तस्मात् । अहः । अजायत ॥ १ ॥

स वै रात्र्या अजायत तस्माद् रात्रिरजायत ॥ २ ॥

॰वै । रात्र्याः । अजायत । तस्मात् । रात्रिः । अजायत ॥ २ ॥

स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥ ३ ॥

॰वै । अन्तरिक्षात् । अजायत । तस्मात् । अन्तरिक्षम् । अजायत ॥ ३ ॥

स वै वायोरजायत तस्माद् वायुरजायत ॥ ४ ॥

॰वै । वायोः । अजायत । तस्मात् । वायुः । अजायत ॥ ४ ॥

स वै दिवोऽजायत तस्माद् द्यौरध्यजायत ॥ ५ ॥

॰वै । दिवः । अजायत । तस्मात् । द्यौः । अधि । अजायत ॥ ५ ॥

स वै दिग्भ्योऽजायत तस्माद् दिशोऽजायन्त ॥ ६ ॥

॰वै । दिक्ऽभ्यः । अजायत । तस्मात् । दिशः । अजायन्त ॥ ६ ॥

स वै भूमेरजायत तस्माद् भूमिरजायत ॥ ७ ॥

॰वै । भूमेः । अजायत । तस्मात् । भूमिः । अजायत ॥ ७ ॥

स वा अग्नेरजायत तस्मादग्निरजायत ॥ ८ ॥

॰वै । अग्नेः । अजायत । तस्मात् । अग्निः । अजायत ॥ ८ ॥

स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥ ९ ॥

॰वै । अत्ऽभ्यः । अजायत । तस्मात् । आपः । अजायन्त ॥ ९ ॥

स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥ १० ॥

॰वै । ऋक्ऽभ्यः । अजायत । तस्मात् । ऋचः । अजायन्त ॥ १० ॥

स वै यज्ञादजायत तस्माद् यज्ञोऽजायत ॥ ११ ॥

सः । वै । यज्ञात् । अजायत । तस्मात् । यज्ञः । अजायत ॥ ११ ॥

स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥ १२ ॥

---

१ C D वाह्नो for वा अह्नो. २ A B B^h C D E R S^m Cs P J Cp भूमेर॰. Dc भूमेर॰ changed to भूमेर॰. We with K K^m V P^2. ३ A B B^h C D E R S^m Cs P J Cp तस्माद्भूमिर॰. Dc भूमिर॰ changed to भूमिर॰. We with K K^m V P^2.

सः । यज्ञः । तस्य॑ । यज्ञः । सः । यज्ञस्य॑ । शिरः॑ । कृतम् ॥ १२ ॥

स स्तनयति स वि द्योतते स उ अश्मा॑नमस्यति ॥ १३ ॥

सः । स्तनयति । सः । वि । द्योतते । सः । ऊं इति॑ । अश्मा॑नम् । अस्यति ॥ १३ ॥

पापाय॑ वा भद्राय॑ वा पुरु॑षायासु॑राय वा ॥ १४ ॥

पापाय॑ । वा । भद्राय॑ । वा । पुरु॑षाय । असु॑राय । वा ॥ १४ ॥

यद्वा॑ कृणोष्योष॑धीर्यद्वा वर्ष॑सि भद्रया यद्वा॑ जन्यम॑वी॑वृधः ॥ १५ ॥

यत् । वा । कृणोषि॑ । ओष॑धीः । यत् । वा । वर्ष॑सि । भद्रया॑ । यत् । वा । जन्यम् । अ॑-वी॑वृधः ॥ १५ ॥

तावां॑स्ते मघवन् महिमोपो॑ ते तन्वः॑ शतम् ॥ १६ ॥

तावा॑न् । ते । मघऽवन् । महिमा । उपो इति॑ । ते । तन्वः॑ । शतम् ॥ १६ ॥

उपो॑ ते बध्वे[2] बद्धा॑नि यदि वासि न्य॑र्बुदम् ॥ १७ ॥ (१८)

उपो इति॑ । ते । बध्वे॑[2] । बद्धा॑नि । यदि॑ । वा । असि॑ । निऽअ॑र्बुदम् ॥ १७ ॥ (१८)

इति चतुर्थेनुवाके चतुर्थं पर्यायसूक्तम् ॥

भूयानिन्द्रो॑ नमुराद् भूया॑निन्द्रासि मृत्युभ्यः॑ ॥ १ ॥

भूया॑न् । इन्द्रः॑ । नमुरात् । भूया॑न् । इन्द्र । असि । मृत्युऽभ्यः॑ ॥ १ ॥

भूयानरा॑त्याः शच्याः पतिस्त्वमि॑न्द्रासि विभूः प्रभूरिति त्वोपा॑स्महे वयम् ॥ २ ॥

भूया॑न् । अरा॑त्याः । शच्याः॑ । पतिः॑ । त्वम् । इन्द्र । असि । विऽभूः । प्रऽभूः । इति॑ । त्वा । उप॑ । आस्महे । वयम् ॥ २ ॥

नम॑स्ते अस्तु पश्यत पश्य॑ मा पश्यत ॥ ३ ॥

नमः॑ । ते । अस्तु । पश्यत । पश्य॑ । मा । पश्यत ॥ ३ ॥

अन्नाद्येन यश॑सा तेज॑सा ब्राह्मणवर्च॑सेन॑ ॥ ४ ॥

---

१ All our authorities have जन्यम॑वीवृधः (the pada-authorities अवीवृधः ।.) २ A D S̊ बध्वे बद्धा॑°. R बद्धे बद्धा॑°. Cs बध्वे बधा॑°. E बद्धे बद्धा॑°. B̊ C P J बद्धे बद्धा॑°. P̊ बद्धे॑ । बद्धानि॑ ।. K K̊ V बध्वे॑ बद्धा°. Dc बद्धे बद्धा॑° changed to बध्वे॑ बद्धा°. Cp बद्धे॑ । बद्धा॑नि । changed from बद्धे॑ । बद्धानि॑ ।. Rw बद्धे बद्धा॑नि.

अन्नऽअद्येन । यशसा । तेजसा । ब्राह्मणऽवर्चसेन ॥ ४ ॥

अम्भो अमो महः सह इति त्वोपास्महे वयम् ।०।० ॥ ५ ॥[1]

अम्भः । अमः । महः । सहः । इति ।० ॥ ५ ॥

अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ।०।० ॥ ६ ॥ (१९)

अम्भः । अरुणम् । रजतम् । रजः । सहः । इति ।० ॥ ६ ॥ (१९)

इति चतुर्थेनुवाके पञ्चमं पर्यायसूक्तम् ॥

उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ।०।० ॥ १ ॥

उरुः । पृथुः । सुऽभूः । भुवः । इति ।० ॥ १ ॥

प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ।०।० ॥ २ ॥

प्रथः[2] । वरः । व्यचः । लोकः । इति ।० ॥ २ ॥

भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति[3] त्वोपास्महे वयम् ॥ ३ ॥

भवत्ऽवसुः । इदत्ऽवसुः । संयत्ऽवसुः । आयत्ऽवसुः । इति । त्वा । उप । आस्महे । वयम् ॥ ३ ॥

नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥ ४ ॥

नमः । ते । अस्तु । पश्यत । पश्य । मा । पश्यत ॥ ४ ॥

अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥ ५ ॥ (२०)

अन्नऽअद्येन । यशसा । तेजसा । ब्राह्मणऽवर्चसेन ॥ ५ ॥ (२०)

चतुर्थेनुवाके षष्ठं पर्यायसूक्तम् ॥

चतुर्थोनुवाकः ॥

इति त्रयोदशं काण्डं समाप्तम् ॥

---

१ The Vaidikas repeat the two lines नमस्ते and अन्नाद्येन after this verse as also after the following one and after each of the first two verses of the next paryâya-sûkta. This would not interfere with the number of the verses composing the paryâya-sûktas as intermediate repetitions do not come in the enumeration. There is nothing in the *Sarvânukramaṇî* or the *Pañchapaṭalikâ* inconsistent with the Vaidikas' repetition. **C D E R $\overset{m}{S}$ D**c indicate the repetition and the other MSS. are not opposed to it. २ **$\overset{2}{P}$ J** प्रथः ।. ३ **K** °राजद्वसु°.

विवाहपरमेतत् काण्डम् । तत्र वक्ष्यमाणानि कर्माणि भवन्ति । तेषु तत्तन्मन्त्रविनियोगाः सूत्रकारेण प्रायोऽन्वर्थमेव कृतास्ते कौशिके दशमेध्याये विस्तरेण प्रपञ्चितास्तत्रैव द्रष्टव्याः । अत्र तु कर्मक्रमस्य मन्त्रवद् दिग्दर्शनम् ॥

सूक्तारम्भे सूर्या नाम या सूर्यरूपा सवितृपुत्री देवी तस्या विवाहस्य कथा वर्णिता ॥

कर्मक्रमस्तु यथा वक्ष्यते ।

विवाहः । स कुमार्याः पितृगृहे । सत्येनोत्तभितेति षोडश पूर्वापरमिति १. २३, २४ द्वे इत्यष्टादशभिराज्यहोमः । आगमक्शरं कुमारीमाशयति[1] ॥ हस्तगृहीतशरावसंपुटं सानुचरं कंचिद् वरं प्रति प्रेषयति । १. ३१ ॥ ब्राह्मणप्रेषणम् । १. ३१ ॥ कुमारीरक्षार्थं पालप्रेषणम् । १. ३४ ॥ उदकग्रहणार्थं व्रजनम् ॥ अप्सु लोष्टं प्रक्षिपति । १. ३७ ॥ अवगाहनम् । १. ३८ ॥ उदकघटपूरणम् । १. ३८ ॥ उदकघटम् उदाहाराय प्रयच्छति । १. ३९ ॥ शाखायां घटनिधानम् ॥ तेनोदकेन सर्वोदकार्थकरणम् ॥ आज्यहोमः । १. १७ ॥ कुमारीकेशविचर्तनम् । १. ५८ ॥ ईशानकोणे तिष्ठन्त्याः कुमार्या उष्णोदकेन आप्लावनम् । २. ६५ ॥ शीतोदकेन सेचनम् । १. ३५, १. ४३ ॥ वाससाङ्गानि प्रमार्ष्टि ॥ तत् कुमारी पालाय प्रयच्छति । २. ६६, ६७ ॥ तद्वासस्तुम्बरदण्डेन गृहीत्वा गोपाटे प्रक्षिपति ॥ अहतेन वाससा तामाच्छादयति । १. ४५, ५३ ॥ यज्ञोपवीतवद्वाधूयं वस्त्रं बध्नाति ॥ केशप्रलेखनम् । २. ६८ ॥ योक्त्रस्य कटिप्रदेशे बन्धनम् । १. ४२, २. ७० ॥ ज्येष्ठीमधुमणे रक्तसूत्रेण बन्धनम्[2] अनामिकायाम् ॥ कन्यादानाद् अनन्तरम् उपाध्यायः कुमारीं हस्ते गृहीत्वा कौतुकगृहान्निर्णयति ॥ शाखायां युगं धारयति । १. २० ॥ दक्षिणतस्तत् पुरुषो धारयति । कन्याया ललाटप्रदेशे हिरण्यबन्धनम् । १. ४०, ४१ । तदुपरि युगच्छिद्रादुदकनिनयनम् ॥ कुमार्या अश्मारोहणम् । १. ४७ ॥ तया लाजहोमः । २. ६३ ॥ वरेण पाणिग्रहणम् । १. ४८–५२ ॥ वरः कन्याम् अग्निं त्रिः परिणयति । १. ३९ ॥ सप्तलेखालेखनम्[3] ॥ तासु वधूमुत्क्रामयति ॥ तल्प उपवेशयति । २. ३१, १. ६० ॥ उपविष्टायास्तस्याः पादौ सुहृत् प्रक्षालयति ॥ कुमारीकटिवेष्टितं योक्त्रं मोचयति । १. ५७,५८ ॥ तद्योक्त्रे भृत्याः संरभन्ते । ये जयन्ति ते बलीयांसो मन्यन्ते ॥ वधूः सर्वौषधीर्वरमूर्ध्नि पलाशपत्रेणावपति । २. ५३–५८ ॥ कुमारीं तल्पाद् उत्थापयति । १. ५९, ६०, ६२ ॥ इति विवाहः ॥

अथोद्वाहः । तत्र वरस्य गृहे वधूनयनम् । तद्यथा । वधूवरौ यानमारोहयति । १. ६१, २. ३० ॥ कर्ता अग्रे व्रजति । २. ८, १. ६४ ॥ दक्षिणेन पादेन प्रक्रामति अध्वानम् । २. ११, १. ३४ ॥ तेनैवाह्ना यद्यन्याप्यूढा तर्हि वधूवस्त्रस्य दशाखण्डं गृहीत्वा चतुष्पथे क्षिप्त्वा दक्षिणेन पादेन तदुपरि तिष्ठति तत् प्रायश्चित्तम् । २. ७४ ॥ उभयोरूढयोः शुभकामः सन् जपं कुर्यात् । २. ४६ ॥ अन्तरा ब्रह्माणम् अतिक्रमयतः ॥ यानस्य विनिष्करणम् । २. ४७ ॥ अध्वनि तीर्थे आयाते लोष्टं प्रक्षिप्य तत उत्तरति । २. ६ ॥ महावृक्षेषु दृष्टेषु जपति । २. ९ ॥ वध्वीक्षणार्थं कुदृक्षु स्त्रीष्वागतासु ताः प्रति जपति । २. २८ ॥ द्वैभेदं (सिन्धुसंगमं) दृष्ट्वा जपति । २. ७ ॥ ओषधीनदीक्षेत्रवनेषु दृष्टेषु जपति । २. ७ ॥ श्मशाने दृष्टे जपति । २. ७३ ॥ अध्वनि सुप्तायां वध्वां प्रबोधयति मन्त्रेण । २. ७५ ॥ वरपितृगृह आसन्नागते जपति । २. १२ ॥ गृहमागते याने तद् अद्भिः संप्रोक्ष्य बलीवर्दौ विमोचयति । २. १६ ॥ निर्ऋत्यपनोदाय पत्नीशालां प्रोक्षति । २. १९ ॥ दक्षिणतो गृहपार्श्वे गोमयपिण्डेश्मानं स्थापयति । १. ४७ ॥ तस्योपरि पलाशस्य यत्पर्णत्रितयं तस्माद् मध्यमपर्णं गृहीत्वा स्थापयति तस्योपरि घृतं घृतस्योपरि चत्वारि दूर्वाग्राणि तदुपरि वधूं स्थापयति । १. ४७ ॥ तस्माद् वधूं प्रपाद्य वरगृहे प्रवेशयति । २. २६, १. २१, १. ६३, १. ६४ । पूर्णपात्रेण कुम्भफलेन अक्षतसहितेन प्रवेशः ॥ अग्निं प्रज्वाल्य ततो हस्तग्रहणं कृत्वा वरो वधूं परिणयति । २. १७,१८ ॥ अग्निसरस्वतीपितृसूर्यादेवमित्रवरुणेभ्यो नमस्कुर्वतीम् अनुमन्त्रयते । २. २०, २. ४६ ॥ कश्चिद् रोहितचर्म आहरति । २. २१ । उपस्तृतस्य तस्योपरि बल्बजम् उपस्तृणीते तस्योपरि वधूमारोहयति उपवेशयति च । २. २३ ॥ दक्षिणोत्तरम् उपस्थं कुरुते वधूः ॥ ब्राह्मणायनं कुमारं शुभनामकं तस्या उपस्थ उपवेशयति । २. २४ ॥ कुमाराय फलमोदकादि दत्त्वा तम् उत्थापयति । २. २५ ॥

---

1 See Kâṇḍa II. 36. 2 See I. 34. 3 See V. 1, 6.

तेन भूतेनेत्यादिना वरवध्वौ क्रमेण जुहुतः[1] । २. १–५, २. ४५ ॥ संपातान् आनयति । उदपात्रे उत्तरान् संपातान् आनयति । उदपात्रं वरवध्वोरञ्जल्योर्निनयति । २. ४५ ॥ तेन भूतेनेति[2] रसान् संपात्य तान् स्थालीपाकं च जायापती उपसर्पयति । तत एकस्मिन् स्थाने स्वजनैः सह उपविश्य मिष्टान्नस्य सहाशनं कुर्यात् पतिः ॥ तेनैव सूक्तेन[2] यवानाम् आज्यमिश्राणां पूर्णाञ्जलिं जुहोति ॥ इत्युद्वाहः ॥

अथ चतुर्थिकाकर्म । तद्यथा । सप्त मर्यादा[3] इति वरो व्रीहीन् जुहोति विवाहाग्नौ ॥ अक्ष्यौ नाविति[4] परस्परं वरवध्वावक्षिणी अञ्जाते ॥ महीमूष्विति[5] वरवध्वौ खट्वामालम्भयति आचार्यः । आरोहयति । २. ३१ । तत्र च तामुपवेशयति । २. २३ ॥ संवेशयति च । २. ३२ ॥ तौ वस्त्रेणाच्छादयति[6] ॥ तावभिमुखौ करोति । २. ३७ ॥ इहेमाविति । २. ६४ । वरवध्वौ त्रिः संनुदति ॥ मदुघमणिं पिष्ट्वा औक्षे प्रक्षिप्य वधूवरौ परस्परं संगच्छेते[7] । २. ७१,७२ ॥ ब्रह्म जज्ञानमिति[8] अङ्गुष्ठेन वरः प्रजननदेशं स्पृशति ॥ खट्वाया उत्थापयति वरो वधूम् । २. ४३ ॥ अहतवस्त्रं वरवध्वौ परिधापयति आचार्यः । १. ४५ । ५३, ५५ ॥ वधूसीमन्ते शष्पं निदधाति वरः । १. ५५,५६ । व्रीहियवौ सीमन्ते निदधाति अमन्त्रकम् । दर्भपिञ्जूल्या सीमन्तं विचृतति । शणशकलेन वधूकेशान् परिवेष्टयति ॥ सर्वेण काण्डेन आज्यं जुहोति वरः । प्रायश्चित्तमेतत् ॥ शुल्कद्रव्यं पृथक् करोति इदं तव इदं मामकीयमिति । १.३२ ॥ वाधूयं वस्त्रं ददतं वरमनुमन्त्रयते । १. २५–३० । आचार्यस्तत् प्रतिगृह्णाति । २. ४१, ४२ ॥ तत् स्थाणावासजति । २. ४८ ॥ तद् गृहीत्वा गच्छति । २. ४९ ॥ तद् वृक्षं प्रतिच्छादयति । २. ५० ॥ सर्वे स्नानं कुर्वन्ति । २. ४५ ॥ तेन वाधूयेनाच्छादयत्यात्मानमाचार्यः । २. ५१ ॥ नवं वसानः । २. ४४ । इति जपित्वा आचार्यो गृहं गच्छति ॥ कुमार्यां नीयमानायां पितृगृहे रोदने सति जीवं रुदन्ति । १. ४६ । इत्यनया यदीमे केशिनः । २. ५९–६२ । इति चतसृभिश्चाज्यं जुहोति । तत् प्रायश्चित्तम् ॥ इति चतुर्थिकाकर्म ॥

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ १ ॥

सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।
ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥ १ ॥

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥ २ ॥

सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही ।
अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥ २ ॥

सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥ ३ ॥

सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति । ओषधिम् ।
सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । पार्थिवः ॥ ३ ॥

---

1 See vi. 78, vi. 82 and v. 24. 2 See vi. 78. 3 See v. 1, 6. 4 See vii. 37. 5 See vii. 6, 2. 6 See vii. 38. 7 See i. 34. 8 See iv. 1.

---

१ C °पिषं°. A Sm °पींषं°. D °पींषं°. P P2 J °पीषं°. Cp °पिंशंति ।.

यत् त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥ ४ ॥

यत् । त्वा । सोम । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनः ।
वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥ ४ ॥

आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥ ५ ॥

आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।
ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ ५ ॥

चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
द्यौर्भूमिः कोश आसीद् यदयात् सूर्या पतिम् ॥ ६ ॥

चित्तिः । आः[1] । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।
द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥ ६ ॥

रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद् वासो गाथयैति[2] परिष्कृता ॥ ७ ॥

रैभी । आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।
सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिष्कृता ॥ ७ ॥

स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत् पुरोगवः ॥ ८ ॥

स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।
सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥ ८ ॥

सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्यां यत् पत्ये शंसन्तीं मनसा सवितादंदात् ॥ ९ ॥

सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।
सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥ ९ ॥

---

१ P आ[2] । २ E °यैधि.

मनो अस्या अन आसीद् द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात् सूर्या पतिम् ॥ १० ॥ (१)

मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।
शुक्रौ । अनड्वाहौ । आस्ताम् । यत् । अयात् । सूर्या । पतिम् ॥ १० ॥ (१)

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम्[1] ।
श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥ ११ ॥

ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते । सामनौ । ऐताम् ।
श्रोत्रे इति । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः[2] । चराचरः ॥ ११ ॥

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्यारोहत् प्रयती[3] पतिम् ॥ १२ ॥

शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।
अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ॥ १२ ॥

सूर्याया वहतुः प्रागात् सविता यमवासृजत् ।
मघासु हन्यन्ते[4] गावः फल्गुनीषु व्युह्यते ॥ १३ ॥

सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।
मघासु । हन्यन्ते[4] । गावः । फल्गुनीषु । वि । उह्यते ॥ १३ ॥

यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वामासीत् क्व देष्ट्राय तस्थथुः[5] ॥ १४ ॥

यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।
क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथुः ॥ १४ ॥

यदयातं शुभस्पती वरेयं सूर्यामुप ।
विश्वे देवा अनु तद् वामजानन् पुत्रः पितरमवृणीत[6] पूषा ॥ १५ ॥

यत् । अयातम् । शुभः । पती इति । वरेऽयम्[7] । सूर्याम् । उप ।

---

१ K^m सामनावितः. २ P पथाः ।. ३ E प्रयंती. ४ All our authorities have हन्यंते. (P P² J Cp हन्यंते ।.) Perhaps a चेत् or च is to be understood. ५ D E K^m Cs तस्थतुः. P तस्थथुः ।. ६ K^m पितरावृणीत. ७ All our pada authorities have the avagraha.

विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तर॑म् । अ॒वृ॒णी॒त॒ । पू॒षा ॥ १५ ॥

द्वे ते॑ च॒क्रे सू॑र्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।

अथैकं॑ च॒क्रं यद् गुहा॒ तद॑द्धातय॒ इद् वि॒दुः ॥ १६ ॥

द्वे इति॑ । ते । च॒क्रे इति॑ । सू॑र्ये॑ । ब्र॒ह्माणः॑ । ऋ॒तु॒ऽथा । वि॒दुः ।

अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धा॒तयः॑ । इत् । वि॒दुः ॥ १६ ॥

अ॒र्य॒मणं॑ यजामहे सु॒ब॒न्धुं प॑ति॒वेद॑नम् ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नात् प्रेतो मु॑ञ्चामि॒ नामुतः॑ ॥ १७ ॥

अ॒र्य॒मण॑म् । य॒जा॒म॒हे॒ । सु॒ऽब॒न्धुम् । प॒ति॒ऽवेद॑नम् ।

उ॒र्वा॒रु॒कम्ऽइ॑व । बन्ध॑नात् । प्र । इ॒तः । मु॒ञ्चा॒मि॒ । न । अ॒मुतः॑ ॥ १७ ॥

प्रेतो मु॑ञ्चामि॒ नामुतः॑ सु॒ब॒द्धाम॒मुत॑स्करम् ।

यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥ १८ ॥

प्र । इ॒तः । मु॒ञ्चा॒मि॒ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒रम् ।

यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥ १८ ॥

प्र त्वा॑ मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ ।

ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै ॥ १९ ॥

प्र । त्वा । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवाः॑ ।

ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । स्यो॒नम् । ते॒ । अ॒स्तु॒ । स॒ह॒ऽसं॑भलायै ॥ १९ ॥

भग॑स्त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑ह॒तां रथे॑न ।

गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥ २० ॥(२)

भगः॑ । त्वा । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा । प्र । व॒ह॒ताम् । रथे॑न ।

गृ॒हान् । ग॒च्छ॒ । गृ॒ह॒ऽप॑त्नी । यथा॑ । अस॑ः । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥ २० ॥ (२)

इ॒ह प्रि॒यं प्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि ।

---

१ All our authorities have सूर्यै॑. २ So we with A B^h C D E K R S^m V Cs P J Cp. Dc इद्विदुः changed to इद्विदुः. K^m विदुः. P^2 वि॒दुः ।. The correction to वि॒दुः is not inevitable. ३ P ऐकं॑म् ।. We with P^2 J Cp. ४ D मुचामि॒. P^2 Cp मु॒चा॒मि॒ ।. ५ P भ॒गः ।.

एना पत्या तन्वं[1] सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥ २१ ॥

इह । प्रियम् । प्रऽजायै । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।

एना । पत्या । तन्वम् । सम् । स्पृशस्व । अथ । जिर्विः[2] । विदथम् । आ । वदासि ॥ २१ ॥

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।

क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥ २२ ॥

इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम्[3] ।

क्रीडन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । सुऽअस्तकौ ॥ २२ ॥

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोर्णवम् ।

विश्वान्यो भुवना विचष्ट ऋतूँरन्यो विदधज्जायसे नवः ॥ २३ ॥

पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीडन्तौ । परि । यातः । अर्णवम् ।

विश्वा । अन्यः । भुवना । विऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायसे । नवः ॥ २३ ॥

नवोनवो भवसि जायमानोह्नां केतुरुषसामेष्यग्रम् ।

भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥ २४ ॥

नवःऽनवः । भवसि । जायमानः । अह्नाम् । केतुः । उषसाम् । एषि । अग्रम् ।

भागम् । देवेभ्यः । वि । दधासि । आऽयन् । प्र । चन्द्रमः । तिरसे । दीर्घम् । आयुः ॥ २४ ॥

परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।

कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥ २५ ॥

परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।

कृत्या । एषा । पत्ऽवती । भूत्वा । आ । जाया । विशते । पतिम् ॥ २५ ॥

नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।

एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु[4] बध्यते ॥ २६ ॥

नीलऽलोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।

---

१ B[h] C E तन्वं३सं. We with A D K K[m] R S[m] V Dc Cs. २ So we with all our authorities. In VIII. 1. 6. Sâyaṇa has जिर्वि°, not जिव्रि°. In Ṛigveda the form is जिव्रि, but from Sâyaṇa on Ṛig. 70. 10 it appears the regular form is जिर्वि, and जिव्रि a corruption. ३ P P[2] अश्नुतम् ।. ४ B °बन्ध्वेषु.

एधन्ते। अस्याः। ज्ञातयः। पतिः। बन्धेषु। बध्यते ॥ २६ ॥

अश्लीला तनूर्भवति रुशती पापयामुया।
पतिर्यद् वध्वो३ वाससः स्वमङ्गमभ्यूर्णुते ॥ २७ ॥

अश्लीला। तनूः। भवति। रुशती। पापया। अमुया।
पतिः। यत्। वध्वः। वाससः। स्वम्। अङ्गम्। अभिऽऊर्णुते ॥ २७ ॥

आशसनं विशसनमथो अधिविकर्तनम्।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥ २८ ॥

आऽशसनम्। विऽशसनम्। अथो इति। अधिऽविकर्तनम्।
सूर्यायाः। पश्य। रूपाणि। तानि। ब्रह्मा। उत। शुम्भति ॥ २८ ॥

तृष्टमेतत् कटुकमपाष्ठवद् विषवन्नैतदत्तवे।
सूर्यां यो ब्रह्मा वेद स इद् वाधूयमर्हति ॥ २९ ॥

तृष्टम्। एतत्। कटुकम्। अपाष्ठऽवत्। विषऽवत्। न। एतत्। अत्तवे।
सूर्याम्। यः। ब्रह्मा। वेद। सः। इत्। वाधूऽयम्। अर्हति ॥ २९ ॥

स इत् तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम्।
प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥ ३० ॥ (३)

सः। इत्। तत्। स्योनम्। हरति। ब्रह्मा। वासः। सुऽमङ्गलम्।
प्रायश्चित्तिम्। यः। अधिऽएति। येन। जाया। न। रिष्यति ॥ ३० ॥ (३)

युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु।
ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥ ३१ ॥

युवम्। भगम्। सम्। भरतम्। सम्ऽऋद्धम्। ऋतम्। वदन्तौ। ऋतऽउद्येषु।
ब्रह्मणः। पते। पतिम्। अस्यै। रोचय। चारु। सम्ऽभलः। वदतु। वाचम्। एताम् ॥ ३१ ॥

इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ।
शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्निह वो मनांसि ॥ ३२ ॥

---

१ A B C D E R S[m] P P[2] J C[p] °र्यद्वध्वो°. C[s] °र्यवध्वो°. We with B[h] K K[m] V D[c].
२ So we with all our authorities. ३ P विषऽवन्। C[p] द्विष॰वत्। We with P[2] J.
४ K[m] °वृताद्येषु. ५ P[2] अस्य। ६ B संवर्धयाथ. ७ So all our authorities, not क्र°.

इह । इत् । असाथ । न । परः । गमाथ । इमम् । गावः । प्रऽजया । वर्धयाथ ।
शुभम् । यतीः । उस्रियाः । सोमऽवर्चसः । विश्वे । देवाः । क्रन् । इह । वः । मनांसि ॥ ३२ ॥

इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।
अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥ ३३ ॥

इमम् । गावः । प्रऽजया । सम् । विशाथ । अयम् । देवानाम् । न । मिनाति । भागम् ।
अस्मै । वः । पूषा । मरुतः । च । सर्वे । अस्मै । वः । धाता । सविता । सुवाति ॥ ३३ ॥

अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।
सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥ ३४ ॥

अनृक्षराः । ऋजवः । सन्तु । पन्थानः । येभिः । सखायः । यन्ति । नः । वरेऽयम् ।
सम् । भगेन । सम् । अर्यम्णा । सम् । धाता । सृजतु । वर्चसा ॥ ३४ ॥

यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।
यद् गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥ ३५ ॥

यत् । च । वर्चः । अक्षेषु । सुरायाम् । च । यत् । आऽहितम् ।
यत् । गोषु । अश्विना । वर्चः । तेन । इमाम् । वर्चसा । अवतम् ॥ ३५ ॥

येन महानघ्न्या जघनमश्विना येन वा सुरा ।
येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥ ३६ ॥

येन । महाऽनघ्न्याः । जघनम् । अश्विना । येन । वा । सुरा ।
येन । अक्षाः । अभिऽअसिच्यन्त । तेन । इमाम् । वर्चसा । अवतम् ॥ ३६ ॥

यो अनिध्मो दीदयदप्स्व१न्तर्यं विप्रास ईडते अध्वरेषु ।
अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्या॑वान् ॥ ३७ ॥

यः । अनिध्मः । दीदयत् । अप्ऽसु । अन्तः । यम् । विप्रासः । ईडते । अध्वरेषु ।
अपाम् । नपात् । मधुऽमतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्यऽवान् ॥ ३७ ॥

---

१ S^m विशाथायं. २ A P नि. ३ P अर्य° ।. ४ All our authorities have °ष्वश्विना. The nominative may be construed with युवाम् understood. P^2 has अवतरम् which points to a reading अवताम् ।. ५ So all our authorities, P P^2 J Cp dividing म-हाऽनघ्न्याः ।. ६ A B^h E R ३ for १. ७ S^m वीर्यऽविान्. ८ P has changed °सः to °साः ।.

इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।
यो भद्रो रोचनस्तमुदचामि ॥ ३८ ॥

इदम् । अहम् । रुशन्तम् । ग्राभम् । तनूऽदूषिम् । अप । ऊहामि ।
यः । भद्रः । रोचनः । तम् । उत् । अचामि ॥ ३८ ॥

आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।
अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥ ३९ ॥

आ । अस्यै । ब्राह्मणाः । स्नपनीः । हरन्तु । अवीरऽघ्नीः । उत् । अजन्तु । आपः ।
अर्यम्णः । अग्निम् । परि । एतु । पूषन् । प्रति । ईक्षन्ते । श्वशुरः । देवरः । च ॥ ३९ ॥

शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥ ४० ॥ (४)

शम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आपः । शम् । मेथिः । भवतु । शम् ।
युगस्य । तर्द्म ।
शम् । ते । आपः । शतऽपवित्राः । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् ।
स्पृशस्व ॥ ४० ॥ (४)

खे रथस्य खेनसः खे युगस्य शतक्रतो ।
अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥ ४१ ॥

खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इति शतऽक्रतो ।
अपालाम् । इन्द्र । त्रिः । पूत्वा । अकृणोः । सूर्यऽत्वचम् ॥ ४१ ॥

आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।
पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥ ४२ ॥

आऽशासाना । सौमनसम् । प्रऽजाम् । सौभाग्यम् । रयिम् ।
पत्युः । अनुऽव्रता । भूत्वा । सम् । नह्यस्व । अमृताय । कम् ॥ ४२ ॥

यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।

---

१ E K रोचनस्त्वमुदचामि. २ $\overset{m}{K}$ पर्यैति. ३ $\overset{2}{P}$ पूषम् ।. ४ $\overset{h}{B}$ C D E R $\overset{m}{S}$ ३ for १. We with K $\overset{m}{K}$ V Dc Cs. ५ B E $\overset{m}{K}$ R V Dc त्रिःपूत्वा°. We with A $\overset{h}{B}$ C D K $\overset{m}{S}$ Cs.

एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥ ४३ ॥
यथा । सिन्धुः । नदीनाम् । साम्ऽराज्यम् । सुसुवे । वृषा ।
एव । त्वम् । सम्ऽराज्ञी । एधि । पत्युः । अस्तम् । पराऽइत्य ॥ ४३ ॥

सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।
ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्वाः ॥ ४४ ॥
सम्ऽराज्ञी । एधि । श्वशुरेषु । सम्ऽराज्ञी । उत । देवृषु ।
ननान्दुः । सम्ऽराज्ञी । एधि । सम्ऽराज्ञी । उत । श्वश्वाः ॥ ४४ ॥

या अकृन्तन्नवयन् याश्च तत्निरे[१] या देवीरन्ताँ[२] अभितोऽददन्त ।
तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥ ४५ ॥
याः । अकृन्तन् । अवयन् । याः । च । तत्निरे । याः । देवीः । अन्तान् । अभितः । अददन्त ।
ताः । त्वा । जरसे । सम् । व्ययन्तु । आयुष्मती । इदम् । परि । धत्स्व । वासः ॥ ४५ ॥

जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।
वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥ ४६ ॥
जीवम् । रुदन्ति । वि । नयन्ति । अध्वरम् । दीर्घाम् । अनु । प्रऽसितिम् । दीध्युः । नरः ।
वामम् । पितृऽभ्यः । ये । इदम् । सम्ऽईरिरे । मयः । पतिऽभ्यः । जनये । परिऽस्वजे ॥ ४६ ॥

स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं[३] देव्याः पृथिव्या उपस्थे ।
तमा तिष्ठानुमाद्या[४] सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥ ४७ ॥
स्योनम् । ध्रुवम् । प्रऽजायै । धारयामि । ते । अश्मानम् । देव्याः । पृथिव्याः । उपऽस्थे ।
तम् । आ । तिष्ठ । अनुऽमाद्या । सुऽवर्चाः । दीर्घम् । ते । आयुः । सविता । कृणोतु ॥ ४७ ॥

येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥ ४८ ॥
येन । अग्निः । अस्याः । भूम्याः । हस्तम् । जग्राह । दक्षिणम् ।
तेन । गृह्णामि । ते । हस्तम् । मा । व्यथिष्ठाः । मया । सह । प्रऽजया । च । धनेन । च ॥ ४८ ॥

देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।

---

१ A B C D °यंयाश्च. S̄ᵐ यंन्याश्च. We with B̄ʰ E K K̄ᵐ R V Dc Cs. २ E R °रंतं.
३ B °श्मानं. ४ S̄ᵐ °नुमाद्या.

अ॒ग्निः सु॒भगां॑ जा॒तवे॑दाः पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ॥ ४९ ॥

दे॒वः । ते॒ । स॒वि॒ता । हस्त॑म् । गृ॒ह्णा॒तु॒ । सोमः॑ । राजा॑ । सु॒ऽप्र॒जस॑म्[१] । कृ॒णो॒तु॒ ।

अ॒ग्निः । सु॒ऽभगा॑म् । जा॒तऽवे॑दाः । पत्ये॑ । पत्नी॑म् । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒तु॒ ॥ ४९ ॥

गृ॒ह्णामि॑ ते सौभगत्वाय॒ हस्तं॑ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथास॑ः[२] ।

भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥ ५० ॥ (५)

गृ॒ह्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । अस॑ः[२] ।

भग॑ः । अ॒र्य॒मा । स॒वि॒ता । पु॒रम्ऽधि॒ः । मह्य॑म् । त्वा॒ । अ॒दु॒ः । गार्ह॑ऽपत्याय । दे॒वाः ॥ ५० ॥ (५)

भग॑स्ते॒ हस्त॑मग्रहीत् सवि॒ता हस्त॑मग्रहीत् ।

पत्नी॒ त्वम॑सि॒ धर्म॑णाहं गृ॒हप॑ति॒स्तव॑ ॥ ५१ ॥

भग॑ः । ते॒ । हस्त॑म् । अ॒ग्र॒ही॒त् । स॒वि॒ता । हस्त॑म् । अ॒ग्र॒ही॒त् ।

पत्नी॑ । त्वम् । अ॒सि॒ । धर्म॑णा । अ॒हम् । गृ॒हऽप॑तिः । तव॑ ॥ ५१ ॥

म॒मेयम॑स्तु॒ पोष्या॒ मह्यं॑ त्वाद॒ाद् बृ॒ह॒स्पतिः॑ ।

म॒या पत्या॑ प्रजाव॑[३]ति॒ सं जीव श॒रद॑ः श॒तम् ॥ ५२ ॥

मम॑ । इ॒यम् । अ॒स्तु॒ । पोष्या॑ । मह्य॑म् । त्वा॒ । अ॒दा॒त् । बृ॒ह॒स्पतिः॑ ।

मया॑ । पत्या॑ । प्र॒जाऽव॑[३]ति॒ । सम् । जी॒व॒ । श॒रद॑ः । श॒तम् ॥ ५२ ॥

त्वष्टा॒ वासो॒ व्यद॑धाच्छु॒[४]भे कं बृ॒ह॒स्पतेः॑ प्र॒शिषा॑ कवी॒नाम् ।

तेने॒मां नारीं॑ सवि॒ता भग॑श्च सू॒र्यामि॑व॒ परि॑ धत्तां प्र॒जया॑ ॥ ५३ ॥

त्वष्टा॑ । वास॑ः । वि । अ॒द॒धा॒त् । शु॒भे । कम् । बृ॒ह॒स्पतेः॑ । प्र॒ऽशिषा॑ । क॒वी॒नाम् ।

तेन॑ । इ॒माम् । नारी॑म् । स॒वि॒ता । भग॑ः । च॒ । सू॒र्याम्ऽइ॑व । परि॑ । ध॒त्ता॒म् । प्र॒ऽजया॑ ॥ ५३ ॥

इ॒न्द्रा॒ग्नी द्यावा॑पृथि॒वी मा॑त॒रिश्वा॑ मि॒त्रावरु॑णा भगो॑ अ॒श्विनो॒भा ।

बृ॒ह॒स्पति॑र्म॒रुतो॒ ब्रह्म॒ सोम॑ इ॒मां नारीं॑ प्र॒जया॑ वर्धयन्तु ॥ ५४ ॥

इ॒न्द्रा॒ग्नी इति॑ । द्यावा॑पृथि॒वी इति॑ । मा॒त॒रिश्वा॑ । मि॒त्रावरु॑णा । भग॑ः । अ॒श्विना॑ । उ॒भा ।

बृ॒ह॒स्पतिः॑ । म॒रुत॑ः । ब्रह्म॑ । सोम॑ः । इ॒माम् । नारी॑म् । प्र॒ऽजया॑ । व॒र्ध॒य॒न्तु॒ ॥ ५४ ॥

---

१ P °प्रजंस° ।. २ B^h D K K^m S^m V Cs °यथासंत्, (K uncertain). Dc यथासः changed to यथासंत्. We with A C E R P P^2 J Cp. ३ C E R S^m P J Cp प्रजावति. A B B^h Cs प्रजावंती. We with D K K^m V Dc P^2. ४ K^m °ष्टुंभे.

बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशाँ[१] अकल्पयत् ।
तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥ ५५ ॥

बृहस्पतिः । प्रथमः । सूर्यायाः । शीर्षे । केशान् । अकल्पयत् ।
तेन । इमाम् । अश्विना । नारीम् । पत्ये । सम् । शोभयामसि ॥ ५५ ॥

इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥ ५६ ॥

इदम् । तत् । रूपम् । यत् । अवस्त । योषा । जायाम् । जिज्ञासे । मनसा । चरन्तीम् ।
ताम् । अनु । अर्तिष्ये । सखिऽभिः । नवऽग्वैः । कः । इमान् । विद्वान् । वि । चचर्त ।
पाशान् ॥ ५६ ॥

अहं वि ष्यामि मयि रूपमस्या वेददित् पश्यन् मनसः कुलायम्[२] ।
न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रश्नानो[३] वरुणस्य पाशान् ॥ ५७ ॥

अहम् । वि । स्यामि । मयि । रूपम् । अस्याः । वेदत् । इत् । पश्यन्[४] । मनसः । कुलायम् ।
न । स्तेयम् । अद्मि । मनसा । उत् । अमुच्ये । स्वयम् । श्रश्नानः । वरुणस्य । पाशान् ॥ ५७ ॥

प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।
उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥ ५८ ॥

प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवाः ।
उरुम् । लोकम् । सुऽगम् । अत्र । पन्थाम् । कृणोमि । तुभ्यम् । सहऽपत्न्यै । वधु ॥ ५८ ॥

उद्यच्छध्वमप रक्षो हनाथेमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥ ५९ ॥

उत् । यच्छध्वम् । अप । रक्षः । हनाथ । इमाम् । नारीम् । सुऽकृते । दधात ।
धाता । विपःऽचित् । पतिम् । अस्यै । विवेद । भगः । राजा । पुरः । एतु । प्रऽजा-
नन् ॥ ५९ ॥

भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि[५] ।

---

१ K^m कशाँ. E R केशाँ. २ A E कुलायन्. ३ K^m श्रंथानो. K श्रंध्रानो. ४ P पश्यंत् ।. We with P^2 J Cp. ५ So we with all our authorities. See Rw.

त्वष्टा पिपेश मध्यतोनु वर्ध्रा[1]न्त्सा नो अस्तु सुमङ्गली ॥ ६० ॥

भर्गः । ततक्ष । चतुरः । पादान् । भर्गः । ततक्ष । चत्वारि । उष्प[2]लानि ।
त्वष्टा । पिपेश । मध्यतः । अनु । व[1]र्ध्रान् । सा । नः । अस्तु । सुऽमङ्गली ॥ ६० ॥

सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥ ६१ ॥

सुऽकिंशुकम् । वहतुम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् ।
आ । रोह । सूर्ये[3] । अमृतस्य । लोकम् । स्योनम् । पतिऽभ्यः । वहतुम् । कृणु । त्वम् ॥ ६१ ॥

अभ्रातृघ्नीं[4] वरुणापशुघ्नीं बृहस्पते ।
इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥ ६२ ॥

अभ्रातृऽघ्नीम् । वरुण । अपशुऽघ्नीम् । बृहस्पते ।
इन्द्र । अपतिऽघ्नीम् । पुत्रिणीम् । आ । अस्मभ्यम् । सवितः । वह ॥ ६२ ॥

मा हिंसिष्टं कुमार्यं[6]१ स्थूणे देवकृते पथि ।
शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥ ६३ ॥

मा । हिंसिष्टम् । कुमार्यम्[7] । स्थूणे इति । देवऽकृते । पथि ।
शालायाः । देव्याः । द्वारम् । स्योनम् । कृण्मः । वधूऽपथम् ॥ ६३ ॥

ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥ ६४ ॥ (६)

ब्रह्म । अपरम् । युज्यताम् । ब्रह्म । पूर्वम् । ब्रह्म । अन्ततः । मध्यतः । ब्रह्म । सर्वतः ।
अनाव्याधाम् । देवऽपुराम् । प्रऽपद्य । शिवा । स्योना । पतिऽलोके । वि । राज ॥ ६४ ॥ (६)

प्रथमेनुवाके प्रथमं सूक्तम् ॥

इति प्रथमोनुवाकः ॥

---

१ A वध्रान्त्सा. K K^m °र्ध्रां°. B^h °द्ध्रां°. B seems to correct to °ध्री°. We with C D E R S^m V Dc Cs P P^2 J Cp. २ So we with all our authorities. See Rw. ३ P सूर्ये ।. ४ S^m °तुघ्नी. ५ B corrects to सवितुर्वह. ६ B B^h D K^m R S^m Cs ३ for १. We with C K V Dc. ७ P °र्याम् ।. P^2 °र्यं (omitting म्). We with J Cp. ८ A B B^h Cs शिवां. We with C D E K K^m R S^m V Dc.

तु॒भ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
स नः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने[1] प्र॒जया॑ स॒ह ॥ १ ॥

तुभ्य॑म् । अग्ने॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह ।
सः । नः॒ । पति॑ऽभ्यः । जा॒याम्[2] । दाः । अग्ने[1] । प्र॒ऽजया॑ । स॒ह ॥ १ ॥

पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥ २ ॥

पुन॑रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा ।
दी॒र्घऽआ॑युः । अ॒स्याः । यः । पति॑ः । जीवा॑ति । श॒रदः॑ । श॒तम् ॥ २ ॥

सोम॑स्य जा॒या प्र॑थ॒मं ग॑न्ध॒र्वस्तेऽप॑रः॒ पति॑ः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनु॒ष्य॒जाः ॥ ३ ॥

सोम॑स्य । जा॒या । प्र॒थ॒मम् । ग॒न्ध॒र्वः । ते॒ । अप॑रः । पति॑ः ।
तृ॒तीय॑ः । अ॒ग्निः । ते॒ । पति॑ः । तु॒रीय॑ः । ते॒ । म॒नु॒ष्य॒ऽजाः ॥ ३ ॥

सोमो॑ ददद् ग॑न्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
र॒यिं च॑ पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥ ४ ॥

सोम॑ः । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ ।
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥ ४ ॥

आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना[3] हृ॒त्सु कामा॑ अरंसत ।
अभू॑तं॒ गोपा॒ मिथु॑ना शुभस्पती प्रि॒या अ॑र्य॒म्णो दुर्या॑ँ अशीमहि ॥ ५ ॥

आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना । हृ॒त्ऽसु । कामा॑ः । अ॒रं॒स॒त ।
अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः । प॒ती इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दु॒र्यान् । अ॒शी॒म॒हि॒ ॥ ५ ॥

सा म॑न्दसा॒ना मन॑सा शि॒वेन॑ र॒यिं धे॑हि॒ सर्व॑वीरं वच॒स्य॑म् ।
सु॒गं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थि॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥ ६ ॥

---

१ So we with all our authorities and rightly as अग्ने (to be pronounced अग्गने) begins the pâda. Only P has दाः । अग्ने ।. Dc दा अग्ने changed to दा अग्ने. All others दा अग्ने. Thus the accent though doubtful is that of all reliable MSS. and Vaidikas. २ P जा॒या ।. ३ B^h न्य॑श्विना.

सा । मन्दसाना । मनसा । शिवेन । रयिम् । धेहि । सर्वऽवीरम् । वचस्यम् ।
सुऽगम् । तीर्थम् । सुऽप्रपानम् । शुभः । पती इति । स्थाणुम् । पथिऽस्थाम् । अप ।
दुःऽमतिम् । हतम् ॥ ६ ॥

या ओषधयो या नद्यो३ यानि क्षेत्राणि या वना ।
तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥ ७ ॥

याः । ओषधयः । याः । नद्यः । यानि । क्षेत्राणि । या । वना ।
ताः । त्वा । वधु । प्रजाऽवतीम् । पत्ये । रक्षन्तु । रक्षसः ॥ ७ ॥

एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।
यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥ ८ ॥

आ । इमम् । पन्थाम्[1] । अरुक्षाम । सुऽगम् । स्वस्तिऽवाहनम् ।
यस्मिन् । वीरः । न । रिष्यति । अन्येषाम् । विन्दते । वसु ॥ ८ ॥

इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येधि तस्थुः ।
स्योनास्ते[2] अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम्[3] ॥ ९ ॥

इदम् । सु । मे । नरः । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुतः ।
ये । गन्धर्वाः । अप्सरसः । च । देवीः । एषु । वानस्पत्येषु । ये । अधि । तस्थुः ।
स्योनाः । ते[2] । अस्यै । वध्वै । भवन्तु । मा । हिंसिषुः । वहतुम् । उह्यमानम् ॥ ९ ॥

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनाँ[4] अनु ।
पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥ १० ॥ (७)

ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनान् । अनु ।
पुनः । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥ १० ॥ (७)

मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।
सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥ ११ ॥

---

१ P P² पथाम् ।. २ So we with all our MSS. and Vaidikas. The first two lines have to be construed together and the third independently, addressed to the bride. See Rw. ३ B C °मुह्यमानम्. ४ E R जनँ. ५ P P² J यज्ञियां ।. We with Cp.

मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दंपती इति दम्ऽपती ।
सुऽगेन । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥ ११ ॥

सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
पर्याण[1]द्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत् कृणोतु ॥ १२ ॥

सम् । काशयामि । वहतुम् । ब्रह्मणा । गृहैः । अघोरेण । चक्षुषा । मित्रियेण ।
परिऽआनद्धम् । विश्वऽरूपम् । यत् । अस्ति । स्योनम् । पतिऽभ्यः । सविता । तत् । कृ-
णोतु ॥ १२ ॥

शिवा नारीयमस्तमागन्निमं धाता लोकमस्यै दिदेश ।
तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥ १३ ॥

शिवा । नारी । इयम् । अस्तम् । आ । अगन् । इमम् । धाता । लोकम् । अस्यै । दिदेश ।
ताम् । अर्यमा । भगः । अश्विना । उभा । प्रजाऽपतिः । प्रऽजया । वर्धयन्तु[2] ॥ १३ ॥

आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम्[3] ।
सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥ १४ ॥

आत्मन्ऽवती । उर्वरा[4] । नारी । इयम् । आ । अगन् । तस्याम् । नरः । वपत । बीजम् ।
अस्याम्[3] ।
सा । वः । प्रऽजाम् । जनयत् । वक्षणाभ्यः । बिभ्रती । दुग्धम् । ऋषभस्य । रेतः ॥ १४ ॥

प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।
सिनीवालि प्र जायतां भगस्य सुमतावसत् ॥ १५ ॥

प्रति । तिष्ठ । विऽराट् । असि । विष्णुःऽइव । इह । सरस्वति ।
सिनीवालि । प्र । जायताम् । भगस्य । सुऽमतौ । असत् ॥ १५ ॥

उद् व ऊर्मिः शम्या[5] हन्त्वापो योक्त्राणि मुञ्चत ।
मादुष्[6]कृतौ व्ये[7]नसावघ्न्यावशुनमारताम् ॥ १६ ॥

उत् । वः । ऊर्मिः । शम्याः । हन्तु । आपः । योक्त्राणि । मुञ्चत ।

---

१ B corrects °ण° to °न°. A B^h K R V Dc Cs °न°. We with C D E K^m S^m. २ P वर्धयतु ।. ३ K K^m V P P^2 बीजमस्याम्. Dc °मस्यां changed to °मस्यां. ४ P उर्वरी ।. ५ S^m शम्या[. ६ B °दुःकृतौ. Cs दुःष्कृतौ. ७ D व्येन°.

मा । अर्दुःऽकृतौ । विऽएनसौ । अघ्न्यौ । अर्शुनम् । आ । अरताम् ॥ १६ ॥

अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।

वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमनस्यमाना ॥ १७ ॥

अघोरऽचक्षुः । अपतिऽघ्नी । स्योना । शग्मा । सुऽशेवा । सुऽयमा । गृहेभ्यः ।

वीरऽसूः । देवृऽकामा । सम् । त्वया । एधिषीमहि । सुऽमनस्यमाना ॥ १७ ॥

अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।

प्रजावती[1] वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥ १८ ॥

अदेवृऽघ्नी । अपतिऽघ्नी । इह । एधि । शिवा । पशुऽभ्यः । सुऽयमा । सुऽवर्चाः ।

प्रजाऽवती । वीरऽसूः । देवृऽकामा । स्योना । इमम् । अग्निम् । गार्हऽपत्यम् । सपर्य ॥ १८ ॥

उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद् गृहात् ।

शून्यैषी निर्ऋते याजगन्धो[2][3]त्तिष्ठाराते प्र पत मेह रंस्थाः ॥ १९ ॥

उत् । तिष्ठ । इतः । किम् । इच्छन्ती । इदम् । आ । अगाः । अहम् । त्वा । ईडे । अभिऽभूः । स्वात् । गृहात् ।

शून्यऽएषी । निःऽऋते । या । आऽजगन्थ[3] । उत् । तिष्ठ । अराते । प्र । पत । मा । इह । रंस्थाः ॥ १९ ॥

यदा गार्हपत्यमसपर्यैत्[4] पूर्वमग्निं वधूरियम् ।

अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥ २० ॥ (८)

यदा । गार्हऽपत्यम् । असपर्यैत् । पूर्वम् । अग्निम् । वधूः । इयम् ।

अध । सरस्वत्यै । नारि । पितृऽभ्यः । च । नमः । कुरु ॥ २० ॥ (८)

शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।

सिनीवालि प्र जायतां भगस्य सुमतावसत् ॥ २१ ॥

शर्म । वर्म । एतत् । आ । हर । अस्यै । नार्यै । उपऽस्तिरे ।

सिनीवालि । प्र । जायताम् । भगस्य । सुऽमतौ । असत् ॥ २१ ॥

यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।

---

१ C K[m] प्रजावतीर्वीरसूर्देवृ°. २ E °च°. ३ So we with all our MSS. and Vaidikas.
४ C °मसपर्यैतत्पू°.

तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥ २२ ॥

यम् । बल्बजम् । निऽअस्यथ । चर्म । च । उपऽस्तृणीथन ।

तत् । आ । रोहतु । सुऽप्रजाः । या । कन्या । विन्दते । पतिम् ॥ २२ ॥

उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।

तत्रोपविश्य सुप्रजा इममग्निं संपर्यतु[1] ॥ २३ ॥

उप । स्तृणीहि । बल्बजम् । अधि । चर्मणि । रोहिते ।

तत्र । उपऽविश्य । सुऽप्रजाः । इमम् । अग्निम् । सपर्यतु ॥ २३ ॥

आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।

इह प्रजां जनय पत्ये अस्मै[2] सुज्यैष्ठ्यो भवत् पुत्रस्त एषः ॥ २४ ॥

आ । रोह । चर्म । उप । सीद । अग्निम् । एषः । देवः । हन्ति । रक्षांसि । सर्वा[3] ।

इह । प्रऽजाम् । जनय । पत्ये । अस्मै । सुऽज्यैष्ठ्यः । भवत् । पुत्रः । ते । एषः ॥ २४ ॥

वि तिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो जायमानाः ।

सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥ २५ ॥

वि । तिष्ठन्ताम् । मातुः । अस्याः[4] । उपऽस्थात् । नानाऽरूपाः । पशवः । जायमानाः ।

सुऽमङ्गली । उप । सीद । इमम् । अग्निम् । सम्ऽपत्नी । प्रति । भूष । इह । देवान् ॥ २५ ॥

सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।

स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥ २६ ॥

सुऽमङ्गली । प्रऽतरणी । गृहाणाम् । सुऽशेवा । पत्ये । श्वशुराय । शम्ऽभूः ।

स्योना । श्वश्र्वै । प्र । गृहान् । विश । इमान् ॥ २६ ॥

स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।

स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥ २७ ॥

स्योना । भव । श्वशुरेभ्यः । स्योना । पत्ये । गृहेभ्यः ।

स्योना । अस्यै । सर्वस्यै । विशे । स्योना । पुष्टाय । एषाम् । भव ॥ २७ ॥

सुमङ्गलीरियं वधूरिमां समेत पश्यत ।

सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥ २८ ॥

---

१ C संपर्यत. २ $\overset{m}{K}$ अस्यै. ३ P $\overset{2}{P}$ सर्वाः ।. ४ P अस्याः ।.

सुऽमङ्गलीः। इयम्। वधूः। इमाम्। समऽएत। पश्यत।
सौभाग्यम्। अस्यै। दत्त्वा। दौःऽभाग्यैः। विऽपरेतन॥ २८॥

या दुर्हार्दो युवतयो याश्चेह जरतीरपि।
वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन॥ २९॥

याः। दुःऽहार्दः। युवतयः। याः। च। इह। जरतीः। अपि।
वर्चः। नु। अस्यै। सम्। दत्त। अथ। अस्तम्। विऽपरेतन॥ २९॥

रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम्।
आरोहत् सूर्या सावित्री बृहते सौभगाय कम्॥ ३०॥ (९)

रुक्मऽप्रस्तरणम्। वह्यम्। विश्वा। रूपाणि। बिभ्रतम्।
आ। अरोहत्। सूर्या। सावित्री। बृहते। सौभगाय। कम्॥ ३०॥ (९)

आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै।
इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि॥ ३१॥

आ। रोह। तल्पम्। सुऽमनस्यमाना। इह। प्रऽजाम्। जनय। पत्ये। अस्मै।
इन्द्राणीऽइव। सुऽबुधा। बुध्यमाना। ज्योतिःऽअग्राः। उषसः। प्रति। जागरासि॥ ३१॥

देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः।
सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह॥ ३२॥

देवाः। अग्रे। नि। अपद्यन्त। पत्नीः। सम्। अस्पृशन्त। तन्वः। तनूभिः।
सूर्याऽइव। नारि। विश्वऽरूपा। महिऽत्वा। प्रजाऽवती। पत्या। सम्। भव। इह॥ ३२॥

उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा।
जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि॥ ३३॥

---

१ All our authorities have जरती° (pada जरतीः।), which is not inadmissible as जरतीः may well be a vocative. २ A B^h D E K^m R S^m Dc Cs ३ for १. We with C K V. ३ S^m °स्थं विप°. P अस्तम्।. ४ P अस्यै।. ५ C D S^m P^2 रुक्मप्रस्तरणं. We with A B B^h E K K^m R V Dc Cs P J Cp. Rw have changed the accent to रुक्मप्रस्तरणं, but that does not appear necessary as the compound should be taken as a shashṭhî-tatpurusha in the sense of a 'conch [made] of gold.' ६ P जागरसि।. We with P^2 J Cp. ७ So we with all our authorities except C which reads न्यक्तिं. See Rw.

उत् । तिष्ठ । इतः । विश्ववसो इति विश्वऽवसो । नमसा । ईडामहे । त्वा ।
जामिम् । इच्छ । पितृऽसदम् । निऽअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥ ३३ ॥

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥ ३४ ॥

अप्सरसः । सधऽमादम् । मदन्ति । हविःऽधानम् । अन्तरा । सूर्यम् । च ।
ताः । ते । जनित्रम् । अभि । ताः । परा । इहि । नमः । ते । गन्धर्वऽऋतुना । कृणोमि ॥ ३४ ॥

नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।
विश्वावसो ब्रह्मणा ते नमोभि जाया अप्सरसः परेहि ॥ ३५ ॥

नमः । गन्धर्वस्य । नमसे । नमः । भामाय । चक्षुषे । च । कृण्मः ।
विश्ववसो इति विश्वऽवसो । ब्रह्मणा । ते । नमः । अभि । जायाः । अप्सरसः । परा । इहि ॥३५॥

राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।
अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥ ३६ ॥

राया । वयम् । सुऽमनसः । स्याम । उत् । इतः । गन्धर्वम् । आ । अवीवृताम ।
अगन् । सः । देवः । परमम् । सधऽस्थम् । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥ ३६ ॥

सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।
मर्य इव योषामधिरोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥ ३७ ॥

सम् । पितरौ । ऋत्विये इति । सृजेथाम् । माता । पिता । च । रेतसः । भवाथः ।
मर्यःऽइव । योषाम् । अधि । रोहय । एनाम् । प्रऽजाम् । कृण्वाथाम् । इह । पुष्यतम् ।
रयिम् ॥ ३७ ॥

तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या३ वपन्ति ।
या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥ ३८ ॥

ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।

---

१ See note 7, page 309. २ K[m] नमोभिर्जाया. B नमोभिजाया. ३ A Cs पुंष्यतां. Cp पुष्यतां । changed to पुष्यतं ।. ४ So P[2] P J Cp. Would not the locative be preferable? See foot-note to XII. 3. 29. ५ P एनाम् ।. ६ So we with A B B[h] C D E K K[m] R S[m] V Dc Cs. P[2] पूषम् ।. P Cp पूषन् ।. J पूषन् । changed to पूषन् ।. Rw have changed the accent to पूषं in conformity with the *Rigveda*. ७ K °मुश्रयाति.

या । नः । ऊरू इति । उशती । विऽश्रयाति । यस्याम् । उशन्तः । प्रऽहरेम । शेपः ॥ ३८ ॥

आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥ ३९ ॥

आ । रोह । ऊरुम् । उप । धत्स्व । हस्तम् । परि । स्वजस्व । जायाम् । सुऽमनस्यमानः ।
प्रऽजाम् । कृण्वाथाम् । इह । मोदमानौ । दीर्घम् । वाम् । आयुः । सविता । कृणोतु ॥ ३९ ॥

आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ (१०

आ । वाम् । प्रऽजाम् । जनयतु । प्रजाऽपतिः । अहोरात्राभ्याम् । सम् । अनक्तु । अर्यमा ।
अदुःऽमङ्गली । पतिऽलोकम् । आ । विश । इमम् । शम् । नः । भव । द्विऽपदे[1] । शम् ।
चतुःऽपदे ॥ ४० ॥ (१०)

देवैर्दत्तं मनुना साकमेतद् वाधूयं वासो वध्वश्च वस्त्रम् ।
यो ब्रह्मणे चिकितुषे ददाति स इद् रक्षांसि तल्पानि हन्ति ॥ ४१ ॥

देवैः । दत्तम् । मनुना । साकम् । एतत् । वाधूऽयम् । वासः । वध्वः । च । वस्त्रम् ।
यः । ब्रह्मणे । चिकितुषे । ददाति । सः । इत् । रक्षांसि । तल्पानि । हन्ति ॥ ४१ ॥

यं[2] मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।
युवं ब्रह्मणेनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥ ४२ ॥

यम् । मे । दत्तः । ब्रह्मऽभागम् । वधूऽयोः । वाधूऽयम् । वासः । वध्वः । च । वस्त्रम् ।
युवम् । ब्रह्मणे । अनुऽमन्यमानौ । बृहस्पते । साकम् । इन्द्रः । च । दत्तम् ॥ ४२ ॥

स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो[3] जीवावुषसो विभातीः ॥ ४३ ॥

स्योनात् । योनेः । अधि । बुध्यमानौ । हसामुदौ । महसा । मोदमानौ ।
सुगू इति सुऽगू । सुऽपुत्रौ । सुऽगृहौ । तराथः । जीवौ । उषसः । विऽभातीः ॥ ४३ ॥

नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।
आण्डात् पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥ ४४ ॥

---

१ P द्विपदे ।. २ K^m Cs यन्मे. Dc यन्मे changed to यं मे. ३ DEKDc चराथो. Cs तरथो.

नवम् । वसानः । सुरभिः । सुऽवासाः । उत्ऽआगाम् । जीवः । उषसः । विऽभातीः ।
आ । अण्डात् । पतत्रीऽइव । अमुक्षि । विश्वस्मात् । एनसः । परि ॥ ४४ ॥

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥ ४५ ॥

शुम्भनी इति । द्यावापृथिवी इति । अन्तिसुम्ने इत्यन्तिऽसुम्ने । महिव्रते इति महिऽव्रते ।
आपः । सप्त । सुस्रुवुः । देवीः । ताः । नः । मुञ्चन्तु । अंहसः ॥ ४५ ॥

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥ ४६ ॥

सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च ।
ये । भूतस्य । प्रऽचेतसः । तेभ्यः । इदम् । अकरम् । नमः ॥ ४६ ॥

य ऋते चिदभिश्रिषः[1] पुरा जत्रुभ्य[2] आतृदः ।
संधाता संधिं मघवा पुरूवसुर्[3]निष्कर्ता[4] विहुतं पुनः ॥ ४७ ॥

यः । ऋते । चित् । अभिऽश्रिषः । पुरा । जत्रुऽभ्यः । आऽतृदः ।
सम्ऽधाता । सम्ऽधिम् । मघऽवा । पुरुऽवसुः । निःऽकर्ता । विऽहुतम् । पुनः ॥ ४७ ॥

अपास्मत् तम उच्छतु नीलं पिशङ्गमुत लोहितं यत् ।
निर्दहनी या पृषातक्य[6]स्मिन् तां स्थाणावध्या संजामि ॥ ४८ ॥

अप । अस्मत् । तमः । उच्छतु । नीलम् । पिशङ्गम् । उत । लोहितम् । यत् ।
निःऽदहनी । या । पृषातकी । अस्मिन् । ताम् । स्थाणौ । अधि । आ । सजामि ॥ ४८ ॥

यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः[8] ।
व्यृद्धयो या असमृद्धयो या अस्मिन् ता[9] स्थाणावधि सादयामि ॥ ४९ ॥

यावतीः । कृत्याः । उपऽवासने । यावन्तः । राज्ञः । वरुणस्य । पाशाः ।
विऽऋद्धयः । याः । असम्ऽऋद्धयः । याः । अस्मिन् । ताः । स्थाणौ । अधि । सादयामि ॥ ४९ ॥

---

१ E °श्रृषः. २ K $\overset{m}{\mathrm{K}}$ C D $\overset{m}{\mathrm{S}}$ V जतृभ्य. Cs जरुभ्य. Dc जत्रु° changed to जतृ°. P जत्तु° ।. Cp जतृभ्यः ।. We with A B $\overset{h}{\mathrm{B}}$ E R J $\overset{2}{\mathrm{P}}$. ३ $\overset{h}{\mathrm{B}}$ $\overset{m}{\mathrm{K}}$ R पुरुवसु°. ४ C °निः- कर्ता. ५ P °धंत्ता ।. ६ A C D E K $\overset{m}{\mathrm{K}}$ R $\overset{m}{\mathrm{S}}$ V Dc °क्य३°. $\overset{h}{\mathrm{B}}$ Cs °क्या३°. ७ P उच्छंतु ।. ८ E पाशात्. ९ A C °तां. B D R $\overset{m}{\mathrm{S}}$ Dc °ताः. We with $\overset{h}{\mathrm{B}}$ E K $\overset{m}{\mathrm{K}}$ V Cs.

या मे प्रियतमा तनूः सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम[1] ॥ ५० ॥ (११)

या । मे । प्रियऽतमा । तनूः । सा । मे । बिभाय । वाससः ।
तस्य । अग्रे । त्वम् । वनस्पते । नीविम् । कृणुष्व । मा । वयम् । रिषाम ॥ ५० ॥ (११)

ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।
वासो यत् पत्नीभिरुतं तन्नः स्योनमुप स्पृशात् ॥ ५१ ॥

ये । अन्ताः । यावतीः । सिचः । ये । ओतवः । ये । च । तन्तवः ।
वासः । यत् । पत्नीभिः । उतम् । तत् । नः । स्योनम् । उप । स्पृशात् ॥ ५१ ॥

उशतीः कन्यला इमाः पितृलोकात् पतिं यतीः[2] ।
अव दीक्षामसृक्षत स्वाहा ॥ ५२ ॥

उशतीः । कन्यलाः । इमाः । पितृऽलोकात् । पतिम् । यतीः ।
अव । दीक्षाम् । असृक्षत । स्वाहा ॥ ५२ ॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥ ५३ ॥

बृहस्पतिना । अवऽसृष्टाम् । विश्वे । देवाः । अधारयन् ।
वर्चः । गोषु । प्रऽविष्टम् । यत् । तेन । इमाम् । सम् । सृजामसि ॥ ५३ ॥

बृहस्पतिना॰ ।
तेजो गोषु प्रविष्टं यत् तेन॰ ॥ ५४ ॥

॰॥ तेजः । गोषु । प्रऽविष्टम् । यत् । तेन ।॰ ॥ ५४ ॥

बृहस्पतिना॰ ।
भगो गोषु प्रविष्टो यस्तेन॰ ॥ ५५ ॥

॰॥ भगः । गोषु । प्रऽविष्टः । यः । तेन ।॰ ॥ ५५ ॥

बृहस्पतिना॰ ।
यशो गोषु प्रविष्टं यत् तेन॰ ॥ ५६ ॥

---

१ E रिंशाम. २ All our authorities have पतिंयतीः, the Pada-authorities reading पतिम् । यतीः ।.

०॥ यशः । गोषु । प्रऽविष्टम् । यत् । तेन ।० ॥ ५६ ॥

बृहस्पतिना० ।

पयो गोषु प्रविष्टं यत् तेन० ॥ ५७ ॥

०॥ पयः । गोषु । प्रऽविष्टम् । यत् । तेन ।० ॥ ५७ ॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।

रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥ ५८ ॥

बृहस्पतिना[1] । अवऽसृष्टाम् । विश्वे । देवाः । अधारयन् ।

रसः । गोषु । प्रऽविष्टः । यः । तेन । इमाम् । सम् । सृजामसि ॥ ५८ ॥

यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तो[2]३घम् ।

अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ ५९ ॥

यदि । इमे । केशिनः । जनाः । गृहे । ते । सम्ऽअनर्तिषुः । रोदेन । कृण्वन्तः । अघम् ।

अग्निः । त्वा । तस्मात् । एनसः । सविता । च । प्र । मुञ्चताम् ॥ ५९ ॥

यदीयं दुहिता तव विकेश्यरुदद् गृहे रोदेन कृण्वत्यं[3]१घम् ।

अग्निष्ट्वा० ॥ ६० ॥ (१२)

यदि । इयम् । दुहिता । तव । विऽकेशी । अरुदत् । गृहे । रोदेन । कृण्वती । अघम् ॥० ॥ ६० ॥ (१२)

यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।

अग्निष्ट्वा० ॥ ६१ ॥

यत् । जामयः । यत् । युवतयः । गृहे । ते । सम्ऽअनर्तिषुः । रोदेन । कृण्वतीः । अघम् ॥० ॥ ६१ ॥

यत् ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितं[4]मघकृद्भिरघं कृतम् ।

---

१ P P̊[2] बृहस्पतिनां ।. २ A K १ for ३. None of our authorities read कृण्वन्तोघम्; only P̊[2] has कृण्वन्तः ।, and Dc has changed कृण्वंतो३घं to कृण्वंतो३घं. The MSS. of Rw. also read कृण्वन्तः (see their *Index*). This reading, therefore, appears ancient, traditional and general. It is likely the wrong accent and the kampa were introduced from false anology with कृण्वत्यं१घम् in the next verse. ३ A C D E K̆[m] R S̆[m] Dc Cs ३ for १. We with Ḃ[h] K V. ४ B R निष्ठितमघ°. C निष्ठितमघ° changed to निष्ठितमघ°.

अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥ ६२ ॥

यत्। ते। प्रऽजायाम्। पशुषु। यत्। वा। गृहेषु। निऽस्थितम्। अघकृत्ऽभिः। अघम्। कृतम्।

अग्निः। त्वा। तस्मात्। एनसः। सविता। च। प्र। मुञ्चताम् ॥ ६२ ॥

इयं नार्युप ब्रूते पूर्ल्यान्यावपन्तिका[1]।
दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥ ६३ ॥

इयम्। नारी। उप। ब्रूते। पूर्ल्यानि[1]। आऽवपन्तिका।
दीर्घऽआयुः। अस्तु। मे। पतिः। जीवाति। शरदः। शतम् ॥ ६३ ॥

इहेमाविन्द्र सं नुद[2] चक्रवाकेव दंपती।
प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम्[3] ॥ ६४ ॥

इह। इमौ। इन्द्र। सम्। नुद। चक्रवाकाऽइव[4]। दंपती इति दम्ऽपती।
प्रऽजया। एनौ। सुऽअस्तकौ। विश्वम्। आयुः। वि। अश्नुताम्[3] ॥ ६४ ॥

यदासन्द्यामुपधाने यद् वोपवासने कृतम्।
विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥ ६५ ॥

यत्। आऽसन्द्याम्[5]। उपऽधाने। यत्। वा। उपऽवासने। कृतम्।
विऽवाहे। कृत्याम्। याम्। चक्रुः। आऽस्नाने[6]। ताम्। नि[7]। दध्मसि ॥ ६५ ॥

यद् दुष्कृतं[8] यच्छमलं विवाहे वहतौ च यत्।
तत् संभलस्य कम्बले मृज्महे[9] दुरितं वयम् ॥ ६६ ॥

यत्। दुःऽकृतम्। यत्। शमलम्। विऽवाहे। वहतौ। च। यत्।
तत्। सम्ऽभलस्य। कम्बले। मृज्महे[9]। दुःऽइतम्। वयम् ॥ ६६ ॥

---

१ **A B $\mathbf{B}^{h}$ D E $\mathbf{K}^{m}$ R $\mathbf{S}^{m}$ Dc Cs P $\mathbf{P}^{2}$ J Cp** and the Vaidikas **K V** पूल्पा॰. **C** alone has पूर्ल्या॰. The Prâkṛit form is पुल्ल पोल्ल, पोल, पोल्लय, (see Jacobi's *Ausgewählte Erzählungen* 36, 34) and not पुप्प or पुप्फ, and thus points to an original पूल्य and not पूल्प. The fact that the Vaidikas repeat पूल्प might only show that their reading was derived from the MSS. which they misread. २ **B E** सन्नु॰. ३ **B R J** ॰श्नुतम्. ४ **P** चक्रवाकऽइव।. ५ **P** ॰सद्याम्।. ६ **P $\mathbf{P}^{2}$ J** आस्ना॰. We with **Cp**. ७ **P $\mathbf{P}^{2}$** परि। for नि।. We with **J Cp**. ८ **B D Cs** यद्दुःकृतं. **$\mathbf{S}^{m}$** यद्दुःष्कृ॰. ९ **B D E R $\mathbf{S}^{m}$ Cs P $\mathbf{P}^{2}$ J Cp** मृग्महे.

संभले मलं सादयित्वा कम्बले दुरितं वयम् ।
अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्[1] ॥ ६७ ॥

सम्ऽभले । मलम् । सादयित्वा । कम्बले । दुःऽइतम् । वयम् ।
अभूम । यज्ञियाः । शुद्धाः । प्र । नः । आयूंषि । तारिषत् ॥ ६७ ॥

कृत्रिमः कण्टकः[2] शतदन् य एषः ।
अपास्याः[3] केश्यं मलमप शीर्षण्यं लिखात्[4] ॥ ६८ ॥

कृत्रिमः । कण्टकः । शतऽदन् । यः । एषः ।
अप । अस्याः । केश्यम् । मलम् । अप । शीर्षण्यम् । लिखात् ॥ ६८ ॥

अङ्गादङ्गाद् वयमस्या अप यक्ष्मं नि दध्मसि ।
तन्मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापदुर्वे[5]१न्तरिक्षम् ।
अपो मा प्रापन्मलमेतदग्ने यमं मा प्रापत्[6] पितॄंश्च सर्वान् ॥ ६९ ॥

अङ्गात्ऽअङ्गात् । वयम् । अस्याः[7] । अप । यक्ष्मम्[8] । नि । दध्मसि ।
तत् । मा[9] । प्र । आपत् । पृथिवीम् । मो । उत । देवान् । दिवम् । मा । प्र । आपत् । उरु । अन्तरिक्षम् ।
अपः[10] । मो । प्र । आपत् । मलम् । एतत् । अग्ने । यमम् । मो । प्र । आपत् । पितॄन् । च । सर्वान् ॥ ६९ ॥

सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम्[11] ॥ ७० ॥ (१३)

सम् । त्वा । नह्यामि । पयसा । पृथिव्याः । सम् । त्वा । नह्यामि । पयसा । ओषधीनाम् ।
सम् । त्वा । नह्यामि । प्रऽजया । धनेन । सा । सम्ऽनद्धा । सनुहि । वाजम् । आ । इमम् ॥ ७० ॥ (१३)

अमोहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।

---

१ D $\overset{m}{\mathrm{S}}$ Cs P $\overset{2}{\mathrm{P}}$ J Cp तार्षत्. २ So we with A B $\overset{h}{\mathrm{B}}$ C D E R Cs J. P $\overset{2}{\mathrm{P}}$ कटंकः ।. $\overset{m}{\mathrm{S}}$ कंकतः changed to कंटंकः. Cp कंटंकः changed to कंकतः (without accent). Dc कंटंकः changed to कंकतः. K $\overset{m}{\mathrm{K}}$ V कंकतः. ३ D K R $\overset{m}{\mathrm{S}}$ अपास्याः. ४ K $\overset{m}{\mathrm{K}}$ V $\overset{2}{\mathrm{P}}$ लिखात्. Dc लिखात् changed to लिखात्. ५ A D E R $\overset{m}{\mathrm{S}}$ Cs ३ for १. ६ $\overset{h}{\mathrm{B}}$ $\overset{m}{\mathrm{K}}$ प्रापपितृंश्च. ७ P अस्याः ।. ८ P यक्ष्मन् ।. ९ P मा ।. १० P अपः ।. $\overset{2}{\mathrm{P}}$ आपः ।. ११ A $\overset{h}{\mathrm{B}}$ वाजमेमां.

तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयाव॒है ॥ ७१ ॥

अमः॑ । अ॒हम् । अ॒स्मि॒ । सा । त्वम् । साम॑ । अ॒हम् । अ॒स्मि॒ । ऋक् । त्वम् । द्यौः । अ॒हम् । पृ॒थि॒वी । त्वम् ।

तौ । इ॒ह । सम् । भ॒वा॒व॒ । प्र॒ऽजाम् । आ । ज॒न॒या॒व॒है॒ ॥ ७१ ॥

ज॒नि॒यन्ति॒ ना॒वग्र॑वः पु॒त्रि॒यन्ति॒ सु॒दान॑वः ।

अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये ॥ ७२ ॥

ज॒नि॒ऽयन्ति॑ । नौ॒ । अग्र॑वः । पु॒त्रि॒ऽयन्ति॑ । सु॒ऽदान॑वः ।

अरि॑ष्टासू॒ इत्यरि॑ष्टऽअसू । स॒चे॒व॒हि॒ । बृ॒ह॒ते । वाज॑ऽसातये ॥ ७२ ॥

ये पि॒तरो॑ वधूद॒र्शा इ॒मं व॑ह॒तुमा॒ग॑मन्[1] ।

ते अ॒स्यै व॒ध्वै सं॑पत्न्यै[2] प्र॒जाव॒च्छर्म॑ यच्छन्तु ॥ ७३ ॥

ये । पि॒तरः॑ । व॒धू॒ऽद॒र्शाः । इ॒मम् । व॒ह॒तुम् । आ । अग॑मन्[1] ।

ते । अ॒स्यै । व॒ध्वै । सम्ऽप॑त्न्यै । प्र॒जाऽव॑त् । शर्म॑ । य॒च्छ॒न्तु॒ ॥ ७३ ॥

येदं पू॒र्वाग॑न् र॑[3]शना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा ।

तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥ ७४ ॥

या । इ॒दम् । पूर्वा॑ । अग॑न्[3] । र॒श॒ना॒ऽयमा॑ना । प्र॒ऽजाम् । अ॒स्यै । द्रवि॑णम् । च॒ । इ॒ह । द॒त्त्वा ।

ताम् । व॒ह॒न्तु॒ । अग॑तस्य । अनु॑ । पन्था॑म् । वि॒ऽराट् । इ॒यम् । सु॒ऽप्र॒जाः । अति॑ । अ॒जै॒षी॒त् ॥ ७४ ॥

प्र बु॑ध्यस्व सु॒बु॒धा बु॑[4]ध्यमाना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।

गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥ ७५ ॥ (१४)

प्र । बु॒ध्य॒स्व॒ । सु॒ऽबु॒धा॑ । बुध्य॑माना । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ।

गृ॒हान् । गच्छ॑ । गृ॒हऽप॑त्नी । यथा॑ । अस॑ । दी॒र्घम् । ते॒ । आयुः॑ । स॒वि॒ता । कृ॒णो॒तु॒ ॥ ७५ ॥ (१४)

द्वितीयेनुवाके प्रथमं सूक्तम् ॥

द्वितीयोनुवाकः ॥

इति चतुर्दशं काण्डं समाप्तम् ॥

---

१ A B^h D E K K^m S^m V Cs °गमं. Dc P P^2 J. °गमम् ।. Cp आ । अगमं ।. We with C R.
२ A B B^h संपत्यै. ३ C K S^m V °गन्नश°. K^m Dc °गेन°. P अगन् ।. ४ C बध्यमाना.

अत्र काण्डे व्रात्यमहिमा प्रपञ्च्यते । व्रात्यो नाम उपनयनादिसंस्काररहीनः पुरुषः । सोऽर्थाद् यज्ञादिवेदविहिताः क्रियाः कर्तुं नाधिकारी । न स व्यवहारयोग्यश्चेत्यादि जनमतं मनसिकृत्य व्रात्योधिकारी व्रात्यो महानुभावो व्रात्यो देवप्रियो व्रात्यो ब्राह्मणक्षत्रिययोर्वर्चसो मूलं किंबहुना व्रात्यो देवाधिदेव एवेति प्रतिपाद्यते । यत्र व्रात्यो गच्छति विश्वं जगद् विश्वे च देवास्तत्र तमनुगच्छन्ति तस्मिन् स्थिते तिष्ठन्ति तस्मिंश्चलति ते चलन्ति । यदा स गच्छति राजवत् स गच्छतीत्यादि । न पुनरेतत् सर्वव्रात्यपरं प्रतिपादनम् अपि तु कंचिद्विद्वत्तमं महाधिकारं पुण्यशीलं विश्वसंमान्यं कर्मपरैर्ब्राह्मणैर्विद्विष्टं व्रात्यम् अनुलक्ष्य वचनम् इति मन्तव्यम् ॥

व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत् ॥ १ ॥

व्रात्यः । आसीत् । ईयमानः । एव । सः । प्रजाऽपतिम् । सम् । ऐरयत् ॥ १ ॥

स प्रजापतिः सुवर्णमात्मन्नपश्यत् तत् प्राजनयत् ॥ २ ॥

सः । प्रजाऽपतिः । सुऽवर्णम् । आत्मन् । अपश्यत् । तत् । प्र । अजनयत् ॥ २ ॥

तदेकमभवत् तल्ललाममभवत् तन्महदभवत् तज्ज्येष्ठमभवत् तद् ब्रह्माभवत् तत् तपोऽभवत् तत् सत्यमभवत् तेन प्राजायत ॥ ३ ॥

तत् । एकम् । अभवत् । तत् । ललामम् । अभवत् । तत् । महत् । अभवत् । तत् । ज्येष्ठम् । अभवत् । तत् । ब्रह्म । अभवत् । तत् । तपः । अभवत् । तत् । सत्यम् । अभवत् । तेन । प्र । अजायत ॥ ३ ॥

सोऽवर्धत स महानभवत् स महादेवोऽभवत् ॥ ४ ॥

सः । अवर्धत । सः । महान् । अभवत् । सः । महाऽदेवः । अभवत् ॥ ४ ॥

स देवानामीशां पर्यैत् स ईशानोऽभवत् ॥ ५ ॥

सः । देवानाम् । ईशाम् । परि । ऐत् । सः । ईशानः । अभवत् ॥ ५ ॥

स एकव्रात्योऽभवत् स धनुरादत्त तदेवेन्द्रधनुः ॥ ६ ॥

सः । एकऽव्रात्यः । अभवत् । सः । धनुः । आ । अदत्त । तत् । एव । इन्द्रऽधनुः ॥ ६ ॥

नीलमस्योदरं लोहितं पृष्ठम् ॥ ७ ॥

नीलम् । अस्य । उदरम् । लोहितम् । पृष्ठम् ॥ ७ ॥

नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥ ८ ॥

नीलेन । एव । अप्रियम् । भ्रातृव्यम् । प्र । ऊर्णोति । लोहितेन । द्विषन्तम् । विध्यति । इति । ब्रह्मऽवादिनः । वदन्ति ॥ ८ ॥

इति प्रथमेऽनुवाके प्रथमं पर्यायसूक्तम् ॥

स उदतिष्ठत् स प्राचीं दिशमनु व्यचलत् ॥ १ ॥

सः । उत् । अतिष्ठत् । सः । प्राचीम् । दिशम् । अनु । वि । अचलत् ॥ १ ॥

तं बृहच्च रथंतरं चादित्याश्च विश्वे च देवा अनुव्यचलन् ॥ २ ॥

तम् । बृहत् । च । रथम्ऽतरम् । च । आदित्याः । च । विश्वे । च । देवाः । अनुऽव्यचलन् ॥ २ ॥

बृहते च वै स रथंतराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ ३ ॥

बृहते । च । वै । सः । रथम्ऽतराय । च । आदित्येभ्यः । च । विश्वेभ्यः । च । देवेभ्यः । आ । वृश्चते । यः । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥ ३ ॥

बृहतश्च वै स रथंतरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति तस्य प्राच्यां दिशि ॥ ४ ॥

बृहतः । च । वै । सः । रथम्ऽतरस्य । च । आदित्यानाम् । च । विश्वेषाम् । च । देवानाम् । प्रियम् । धाम । भवति । तस्य । प्राच्याम् । दिशि ॥ ४ ॥

श्रद्धा पुंश्चली मित्रो[1] मागधो[1] विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ ५ ॥

श्रद्धा । पुंश्चली । मित्रः । मागधः । विऽज्ञानम् । वासः । अहः । उष्णीषम् । रात्री । केशाः । हरितौ । प्रऽवर्तौ । कल्मलिः । मणिः ॥ ५ ॥

भूतं च भविष्यच्च परिष्कन्दौ[2] मनो विपथम्[3] ॥ ६ ॥

भूतम् । च । भविष्यत् । च । परिऽस्कन्दौ । मनः । विऽपथम् ॥ ६ ॥

मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः[4] ॥ ७ ॥

मातरिश्वा । च । पवमानः । च । विपथऽवाहौ । वातः । सारथिः । रेष्मा । प्रऽतोदः ॥ ७ ॥

---

१ B[h] C E Cs Cp मित्रो मागधो. R मित्रो मागधो. We with A B D K K[m] S[m] V Dc P P[2] J.
२ D E K S[m] V Dc Cs परिस्कन्दौ. We with A B B[h] C K[m] R. ३ So we with all our authorities. See Rw. ४ So we with all our authorities. See Rw.

कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ ८ ॥

कीर्तिः। च। यशः। च। पुरःऽसरौ। आ। एनम्। कीर्तिः। गच्छति। आ। यशः। गच्छति। यः। एवम्। वेद ॥ ८ ॥

स उदतिष्ठत् स दक्षिणां दिशमनु व्यचलत् ॥ ९ ॥

°सः। दक्षिणाम्। दिशम्।० ॥ ९ ॥

तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥ १० ॥

तम्। यज्ञायज्ञियम्। च। वामऽदेव्यम्। च। यज्ञः। च। यजमानः। च। पशवः। च। अनुऽव्यचलन् ॥ १० ॥

यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ ११ ॥

यज्ञायज्ञियाय। च। वै। सः। वामऽदेव्याय। च। यज्ञाय। च। यजमानाय। च। पशुऽभ्यः। च। आ। वृश्चते।० ॥ ११ ॥

यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति[२] तस्य दक्षिणायां दिशि ॥ १२ ॥

यज्ञायज्ञियस्य। च। वै। सः। वामऽदेव्यस्य। च। यज्ञस्य। च। यजमानस्य। च। पशूनाम्[३]। च। प्रियम्। धाम। भवति। तस्य। दक्षिणायाम्। दिशि ॥ १२ ॥

उषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १३ ॥

उषाः। पुंश्चली। मन्त्रः। मागधः। विऽज्ञानम्। वासः। अहः। उष्णीषम्। रात्री। केशाः। हरितौ। प्रऽवर्तौ। कल्मलिः। मणिः ॥ १३ ॥

अमावास्या च पौर्णमासी च परिष्कन्दौ मनो ०।० ॥ १४ ॥

अमाऽवास्या। च। पौर्णऽमासी। च।० ॥ १४ ॥

---

१ So we with all our authorities. See Rw. २ All our authorities omit य एवं वेद which Rw. insert after भवति. ३ P J पशूनाम्। We with P² Cp.

स उदतिष्ठत् स प्रतीचीं दिशमनु व्यचलत् ॥ १५ ॥

°सः । प्रतीचीम् । दिशम् ।० ॥ १५ ॥

तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् ॥ १६ ॥

तम् । वैरूपम् । च । वैराजम् । च । आपः । च । वरुणः । च । राजा । अनुऽव्यचलन् ॥ १६ ॥

वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ १७ ॥

वैरूपाय । च । वै । सः । वैराजाय । च । अत्ऽभ्यः । च । वरुणाय । च । राज्ञे । आ । वृश्चते ।० ॥ १७ ॥

वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्य प्रतीच्यां दिशि ॥ १८ ॥

वैरूपस्य । च । वै । सः । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञः । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥ १८ ॥

इरा[१] पुंश्चली हसो मागधो[२] विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १९ ॥

इरा । पुंश्चली । हसः । मागधः । विऽज्ञानम् । वासः । अहः । उष्णीषम् । रात्री । केशाः । हरितौ । प्रऽवर्तौ । कल्मलिः । मणिः ॥ १८ ॥

अहश्च रात्री च परिष्कन्दौ[३] मनो०।० ॥ २० ॥

अहः । च । रात्री । च ।० ॥ २० ॥

स उदतिष्ठत् स उदीचीं दिशमनु व्यचलत् ॥ २१ ॥

सः । उत् । अतिष्ठत् । सः । उदीचीम् । दिशम् । अनु । वि । अचलत् ॥ २१ ॥

तं श्यैतं च नौधसं च सप्तर्षयश्च[४] सोमश्च राजानुव्यचलन् ॥ २२ ॥

---

१ So we divide with all our authorities. See **Rw**. We read इरा पुं° with **A B B^h C D E R S^m Cs P J Cp**. **Dc** इरा पुं° changed to इरा पुं°. **K K^m P^2 V** इरां पुं°. The latter MSS. are influenced by the *Rigveda* accent. २ **A D K K^m V P^2** हसो मागधो. **Dc** हसो मागधो changed to हसो मागधो. We with **B^h C E R S^m Cs P J Cp**. ३ See note 2 at page 320. ४ **A B B^h C K K^m R** सप्तऋष°. We with **D E S^m V Dc Cs**.

तम् । श्यैतम् । च । नौधसम् । च । सप्तऽऋषयः । च । सोमः । च । राजा । अनुऽव्यचलन् ॥ २२ ॥

श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ २३ ॥

श्यैताय । च । वै । सः । नौधसाय । च । सप्तर्षिऽभ्यः । च । सोमाय । च । राज्ञे । आ । वृश्चते । यः । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥ २३ ॥

श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥ २४ ॥

श्यैतस्य । च । वै । सः । नौधसस्य । च । सप्तऽऋषीणाम् । च । सोमस्य । च । राज्ञः । प्रियम् । धाम । भवति । तस्य । उदीच्याम् । दिशि ॥ २४ ॥

विद्युत् पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ २५ ॥

विऽद्युत् । पुंश्चली । स्तनयित्नुः । मागधः । विऽज्ञानम् । वासः । अहः । उष्णीषम् । रात्री । केशाः । हरितौ । प्रऽवर्तौ । कल्मलिः । मणिः ॥ २५ ॥

श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथम् ॥ २६ ॥

श्रुतम् । च । विऽश्रुतम् । च । परिऽस्कन्दौ । मनः । विऽपथम् ॥ २६ ॥

मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥ २७ ॥

मातरिश्वा । च । पवमानः । च । विपथऽवाहौ । वातः । सारथिः । रेष्मा । प्रऽतोदः ॥ २७ ॥

कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २८ ॥

कीर्तिः । च । यशः । च । पुरःऽसरौ । आ । एनम् । कीर्तिः । गच्छति । आ । यशः । गच्छति । यः । ० ॥ २८ ॥

इति प्रथमेनुवाके द्वितीयं पर्यायसूक्तम् ॥

स संवत्सरमूर्ध्वोऽतिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥ १ ॥

---

१ C P P̊ J Cp सप्तऋषी°. We with A B B̊ D E K K̊ R S̊ V Dc Cs. २ P °ली: ।. ३ A D E K V Dc Cs परिस्कन्दौ. ४ P P̊ have no *avagraha*. J वि०श्रुतम् । changed to विश्रुतम् ।. We with Cp. ५ B B̊ C E R °ध्वोऽति°. Cs °मूर्द्धोऽति°. We with A D K K̊ S̊ V Dc.

सः । सम्ऽवत्सरम् । ऊर्ध्वः । अतिष्ठत् । तम् । देवाः । अब्रुवन् । व्रात्य । किम् । नु । तिष्ठसि । इति ॥ १ ॥

सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥ २ ॥

सः । अब्रवीत् । आऽसन्दीम् । मे । सम् । भरन्तु । इति ॥ २ ॥

तस्मै व्रात्यायासन्दीं समभरन् ॥ ३ ॥

तस्मै । व्रात्याय । आऽसन्दीम् । सम् । अभरन् ॥ ३ ॥

तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥ ४ ॥

तस्याः । ग्रीष्मः । च । वसन्तः । च । द्वौ । पादौ । आस्ताम् । शरत् । च । वर्षाः । च । द्वौ ॥ ४ ॥

बृहच्च रथंतरं चानूच्ये३ आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये[1] ॥ ५ ॥

बृहत् । च । रथम्ऽतरम् । च । अनूच्ये३ इति । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । तिरश्च्ये३ इति ॥ ५ ॥

ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥ ६ ॥

ऋचः । प्राञ्चः । तन्तवः । यजूंषि । तिर्यञ्चः ॥ ६ ॥

वेद आस्तरणं ब्रह्मोपबर्हणम् ॥ ७ ॥

वेदः । आऽस्तरणम् । ब्रह्म । उपऽबर्हणम् ॥ ७ ॥

सामासाद उद्गीथोऽपश्रयः ॥ ८ ॥

साम[2] । आऽसादः । उत्ऽगीथः । अपऽश्रयः ॥ ८ ॥

तामासन्दीं व्रात्य आरोहत् ॥ ९ ॥

ताम् । आऽसन्दीम् । व्रात्यः । आ । अरोहत् ॥ ९ ॥

तस्य देवजनाः परिष्कन्दा[3] आसन्त्संकल्पाः प्रहाय्या[4]३ विश्वानि भूतान्युपसदः ॥ १० ॥

तस्य । देवऽजनाः । परिऽस्कन्दाः । आसन् । सम्ऽकल्पाः । प्रऽहाय्याः । विश्वानि । भूतानि । उपऽसदः ॥ १० ॥

---

१ D तिरश्च्यै. A B^h E R Cs P P^2 J Cp तिरश्चे. We with C K K^m S^m V Dc. २ P सामा ।. ३ A D E K S^m V Dc Cs परिस्कन्दा. B^h C K^m R परिष्कन्दा. ४ A B E K P प्रहाय्या°. We with B^h C D K^m R S^m V Dc Cs P^2 J Cp.

विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥ ११ ॥

विश्वानि । एव । अस्य । भूतानि । उपऽसदः । भवन्ति । यः ।० ॥ ११ ॥

इति प्रथमेनुवाके तृतीयं पर्यायसूक्तम् ॥

तस्मै प्राच्या दिशः ॥ १ ॥

तस्मै । प्राच्याः । दिशः ॥ १ ॥

वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथंतरं चानुष्ठातारौ ॥ २ ॥

वासन्तौ । मासौ । गोप्तारौ । अकुर्वन् । बृहत् । च । रथम्ऽतरम् । च । अनुऽस्थातारौ ॥ २ ॥

वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथंतरं चानु तिष्ठतो य एवं वेद ॥ ३ ॥

वासन्तौ । एनम् । मासौ । प्राच्याः । दिशः । गोपायतः । बृहत् । च । रथम्ऽतरम् । च । अनु । तिष्ठतः । यः ।० ॥ ३ ॥

तस्मै दक्षिणाया दिशः ॥ ४ ॥

तस्मै । दक्षिणायाः । दिशः ॥ ४ ॥

ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ॥ ५ ॥

ग्रैष्मौ । मासौ । गोप्तारौ । अकुर्वन् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च ।० ॥ ५ ॥

ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥ ६ ॥

ग्रैष्मौ । एनम् । मासौ । दक्षिणायाः । दिशः । गोपायतः । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च ।० ॥ ६ ॥

तस्मै प्रतीच्या दिशः ॥ ७ ॥

तस्मै । प्रतीच्याः । दिशः ॥ ७ ॥

वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ ॥ ८ ॥

वार्षिकौ । मासौ । गोप्तारौ । अकुर्वन् । वैरूपम् । च । वैराजम् । च ।० ॥ ८ ॥

---

१ A B Cs P P̊ J भवति. २ P दिशिः ।. ३ All our MSS. read °रावकु° which is not quite inadmissible. The first sentence may end with गोप्तारौ, and अकुर्वन् may begin a new one. See Rw.

वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥ ९ ॥

वार्षिकौ । एनम् । मासौ । प्रतीच्याः । दिशः । गोपायतः । वैरूपम् । च । वैराजम् । च ।० ॥ ९ ॥

तस्मा उदीच्या दिशः ॥ १० ॥

तस्मै । उदीच्याः । दिशः ॥ १० ॥

शारदौ मासौ गोप्तारावकुर्वञ्छ्यैतं च नौधसं चानुष्ठातारौ ॥ ११ ॥

शारदौ । मासौ । गोप्तारौ । अकुर्वन् । श्यैतम् । च । नौधसम् । च ।० ॥ ११ ॥

शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥ १२ ॥

शारदौ । एनम् । मासौ । उदीच्याः । दिशः । गोपायतः । श्यैतम् । च । नौधसम् । च ।० ॥ १२ ॥

तस्मै ध्रुवाया दिशः ॥ १३ ॥

तस्मै । ध्रुवायाः । दिशः ॥ १३ ॥

हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ॥ १४ ॥

हैमनौ । मासौ । गोप्तारौ । अकुर्वन् । भूमिम् । च । अग्निम् । च ।० ॥ १४ ॥

हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥ १५ ॥

हैमनौ । एनम् । मासौ । ध्रुवायाः । दिशः । गोपायतः । भूमिः । च । अग्निः । च ।० ॥ १५ ॥

तस्मा ऊर्ध्वाया दिशः ॥ १६ ॥

तस्मै । ऊर्ध्वायाः । दिशः ॥ १६ ॥

शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ ॥ १७ ॥

शैशिरौ । मासौ । गोप्तारौ । अकुर्वन् । दिवम् । च । आदित्यम् । च । अनुऽस्थातारौ ॥ १७ ॥

शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥ १८ ॥

---

१ See note 3 at page 325.

शैशिरौ । एनम् । मासौ । ऊर्ध्वायाः । दिशः । गोपायतः । द्यौः । च । आदित्यः । च । अनु । तिष्ठतः । यः ।० ॥ १८ ॥

इति प्रथमेऽनुवाके चतुर्थं पर्यायसूक्तम् ॥

तस्मै प्राच्या दिशो अन्तर्देशाद् भवमिष्वासमनुष्ठातारमकुर्वन् ॥ १ ॥

तस्मै । प्राच्याः । दिशः[1] । अन्तःऽदेशात् । भवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥ १ ॥

भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः[2] ॥ २ ॥

भवः । एनम् । इषुऽआसः । प्राच्याः । दिशः । अन्तःऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्वः । न । भवः । न । ईशानः ॥ २ ॥

नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥ ३ ॥

न । अस्य । पशून् । न । समानान् । हिनस्ति । यः ।० ॥ ३ ॥

तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥ ४ ॥

तस्मै । दक्षिणायाः । दिशः । अन्तःऽदेशात् । शर्वम् । इषुऽआसम् ।० ॥ ४ ॥

शर्व एनमिष्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं० ॥ ५ ॥

शर्वः । एनम् । इषुऽआसः । दक्षिणायाः । दिशः ।० ॥ ५ ॥

तस्मै प्रतीच्या दिशो अन्तर्देशात् पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ॥ ६ ॥

तस्मै । प्रतीच्याः । दिशः । अन्तःऽदेशात् । पशुऽपतिम्[3] । इषुऽआसम् ।० ॥ ६ ॥

पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनु० ॥ ७ ॥

पशुऽपतिः[4] । एनम् । इषुऽआसः । प्रतीच्याः । दिशः ।० ॥ ७ ॥

तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥ ८ ॥

तस्मै । उदीच्याः । दिशः । अन्तःऽदेशात् । उग्रम् । देवम् । इषुऽआसम् ।० ॥ ८ ॥

उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनु० ॥ ९ ॥

---

१ P दिशिः ।. २ So we with all our authorities. See Rw. ३ P पशू° ।. ४ P पशू° ।.

उग्रः । एनम् । देवः । इषुऽआसः । उदीच्याः । दिशः ।० ॥ ९ ॥

तस्मै ध्रुवाया दिशो अन्तर्देशाद् रुद्रमिष्वासमनुष्ठातारमकुर्वन् ॥ १० ॥

तस्मै । ध्रुवायाः । दिशः । अन्तःऽदेशात् । रुद्रम् । इषुऽआसम् ।० ॥ १० ॥

रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनु० ॥ ११ ॥

रुद्रः । एनम् । इषुऽआसः । ध्रुवायाः । दिशः ।० ॥ ११ ॥

तस्मा ऊर्ध्वाया दिशो अन्तर्देशान्महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥ १२ ॥

तस्मै । ऊर्ध्वायाः । दिशः । अन्तःऽदेशात् । महाऽदेवम्[1] । इषुऽआसम् ।० ॥ १२ ॥

महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनु० ॥ १३ ॥

महाऽदेवः[1] । एनम् । इषुऽआसः । ऊर्ध्वायाः । दिशः । अन्तःऽदेशात् । अनुऽस्थाता ।० ॥ १३ ॥

तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ॥ १४ ॥

तस्मै । सर्वेभ्यः । अन्तःऽदेशेभ्यः । ईशानम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥ १४ ॥

ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥ १५ ॥

ईशानः । एनम् । इषुऽआसः । सर्वेभ्यः । अन्तःऽदेशेभ्यः । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्वः । न । भवः । न । ईशानः ॥ १५ ॥

नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥ १६ ॥

न । अस्य । पशून् । न । समानान्[3] । हिनस्ति । यः ।० ॥ १६ ॥

इति प्रथमेनुवाके पञ्चमं पर्यायसूक्तम् ॥

स ध्रुवां दिशमनु व्यचलत् ॥ १ ॥

सः । ध्रुवाम् । दिशम् । अनु । वि । अचलत् ॥ १ ॥

तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ॥ २ ॥

तम् । भूमिः । च । अग्निः । च । ओषधयः । च । वनस्पतयः । च । वानस्पत्याः । च । वीरुधः । च । अनुऽव्यचलन् ॥ २ ॥

१ P मा° ।. २ A B[h] omit अ°. ३ P समानाम् ।.

भूमेश्च वै सो[1]३ग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वी-
रुधां च प्रियं धाम भवति य एवं वेद ॥ ३ ॥

भूमेः । च । वै । सः । अग्नेः । च । ओषधीनाम् । च । वनस्पतीनाम् । च । वानस्पत्यानाम् । च । वीरुधाम् । च । प्रियम् । धाम । भवति । यः ।० ॥ ३ ॥

स ऊर्ध्वां दिशमनु व्यचलत् ॥ ४ ॥

सः । ऊर्ध्वाम् । दिशम् ।० ॥ ४ ॥

तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥ ५ ॥

तम् । ऋतम् । च । सत्यम् । च । सूर्यः । च । चन्द्रः । च । नक्षत्राणि । च ।० ॥ ५ ॥

ऋतस्य च[2] वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं
धाम भवति य एवं वेद ॥ ६ ॥

ऋतस्य । च । वै । सः । सत्यस्य । च । सूर्यस्य । च । चन्द्रस्य । च । नक्षत्राणाम् । च ।० ॥ ६ ॥

स उत्तमां दिशमनु व्यचलत् ॥ ७ ॥

सः । उत्ऽतमाम् । दिशम् ।० ॥ ७ ॥

तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥ ८ ॥

तम् । ऋचः । च । सामानि । च । यजूंषि । च । ब्रह्म । च ।० ॥ ८ ॥

ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं
वेद ॥ ९ ॥

ऋचाम् । च । वै । सः । साम्नाम् । च । यजुषाम् । च । ब्रह्मणः । च ।० ॥ ९ ॥

स बृहतीं दिशमनुव्यचलत् ॥ १० ॥

सः । बृहतीम् । दिशम् ।० ॥ १० ॥

तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥ ११ ॥

---

१ **K V D**c १ for ३. **A D E K**[m] **R S**[m] **C**s no sign of kampa, but read सोग्नेश्चौ°. We with **B B**[h] **C.** २ So we with all our authorities. **R**w who omit च in their Edition restore it in their *Index*.

तम् । इतिहऽआसः । च । पुराणम् । च । गाथाः । च । नाराशंसीः । च ।० ॥ ११ ॥

इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥ १२ ॥

इतिहऽआसस्य । च । वै । सः । पुराणस्य । च । गाथानाम् । च । नाराशंसीनाम् । च ।० ॥ १२ ॥

स परमां दिशमनु व्यचलत् ॥ १३ ॥

सः । परमाम् । दिशम् ।० ॥ १३ ॥

तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥ १४ ॥

तम् । आऽहवनीयः । च । गार्हऽपत्यः । च । दक्षिणऽअग्निः । च । यज्ञः । च । यजमानः । च । पशवः । च ।० ॥ १४ ॥

आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥ १५ ॥

आऽहवनीयस्य । च । वै । सः । गार्हऽपत्यस्य । च । दक्षिणऽअग्नेः । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम्[१] । च ।० ॥ १५ ॥

सोनादिष्टां दिशमनु व्यचलत् ॥ १६ ॥

सः । अनादिष्टाम् । दिशम् ।० ॥ १६ ॥

तमृतवश्चार्तवाश्च लोकाश्च[२] लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् ॥ १७ ॥

तम् । ऋतवः । च । आर्तवाः । च । लोकाः[२] । च । लौक्याः । च । मासाः । च । अर्धऽमासाः । च । अहोरात्रे इति । च ।० ॥ १७ ॥

---

१ P J पशूनाम् ।. २ A B B[h] C D E K[m] R S[m] Cs P J Cp °श्च लोकाश्च. Dc changes च लोकाश्च to च लोकाश्च. P[2] लोकाः ।. K and V alone recite च लोकाश्च, but theirs is surely not the original Atharvan reading but a recent correction. The MSS. of Rw too have च लोकाश्च (*vide* their *Index.*) The accent, therefore, though irregular is certainly the genuine Atharvan accent.

ऋतूनां च वै स आर्तवानां च लोकानां[1] च लौक्यानां च मासानां चा-
र्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥ १८ ॥

ऋतूनाम् । च । वै । सः । आर्तवानाम् । च । लोकानाम्[1] । च । लौक्यानाम् । च । मा-
सानाम् । च । अर्धऽमासानाम् । च । अहोरात्रयोः । च ।० ॥ १८ ॥

सोनावृत्तां दिशमनु व्यचलत् ततो नावर्त्स्यन्नमन्यत[2] ॥ १९ ॥

सः । अनावृत्ताम् । दिशम् । अनु । वि । अचलत् । ततः । न । आऽवर्त्स्यन् । अमन्यत[3] ॥ १९ ॥

तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥ २० ॥

तम् । दितिः । च । अदितिः । च । इडा । च । इन्द्राणी । च । अनुऽव्यचलन् ॥ २० ॥

दितेश्च वै सोदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥ २१ ॥

दितेः । च । वै । सः । अदितेः । च । इडायाः । च । इन्द्राण्याः । च । प्रियम् ।० ॥ २१ ॥

स दिशोनु व्यचलत् तं विराडनु व्यचलत् सर्वे च देवाः सर्वाश्च दे-
वताः ॥ २२ ॥

सः । दिशः । अनु । वि । अचलत् । तम् । विऽराट् । अनु । वि । अचलत् । सर्वे । च ।
देवाः । सर्वाः । च । देवताः ॥ २२ ॥

विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भ-
वति य एवं वेद ॥ २३ ॥

विऽराजः । च । वै । सः । सर्वेषाम् । च । देवानाम् । सर्वासाम् । च । देवतानाम् ।
प्रियम् ।० ॥ २३ ॥

स सर्वानन्तर्देशाननु व्यचलत् ॥ २४ ॥

सः । सर्वान् । अन्तःऽदेशान् । अनु । वि । अचलत् ॥ २४ ॥

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ॥ २५ ॥

तम् । प्रजाऽपतिः । च । परमेऽस्थी । च । पिता । च । पितामहः । च । अनुऽव्यचि-
लन् ॥ २५ ॥

---

१ Here too A B B^h C D E R S^m Cs P P^2 J Cp have च लोकानां. Dc लोकानां as an after correction. K K^m V alone have लोकानां, but theirs is not the old true Atharvan tradition. २ S^m °मन्यत्. ३ P अमन्यत् ।.

प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥ २६ ॥

प्रजाऽपतेः । च । वै । सः । परमेऽस्थिनः । च । पितुः । च । पितामहस्य । च । प्रियम् । धाम । भवति । यः ।० ॥ २६ ॥

इति प्रथमेनुवाके षष्ठं पर्यायसूक्तम् ॥

स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत् स[1] समुद्रोऽभवत् ॥ १ ॥

सः । महिमा । सद्रुः । भूत्वा । अन्तम् । पृथिव्याः । अगच्छत् । सः । समुद्रः । अभवत् ॥ १ ॥

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥ २ ॥

तम् । प्रजाऽपतिः । च । परमेऽस्थी । च । पिता । च । पितामहः । च । आपः । च । श्रद्धा । च । वर्षम् । भूत्वा । अनुऽव्यवर्तयन्त ॥ २ ॥

ऐनमापो गच्छ[2]त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥ ३ ॥

आ । एनम् । आपः । गच्छ[2]ति । आ । एनम् । श्रद्धा । गच्छति । आ । एनम् । वर्षम् । गच्छति । यः ।० ॥ ३ ॥

तं श्रद्धा च यज्ञश्च लोक[3]श्चान्नं चान्नाद्यं च भूत्वाभि[4]पर्यावर्तन्त ॥ ४ ॥

तम् । श्रद्धा । च । यज्ञः । च । लोकः[3] । च । अन्नम् । च । अन्नऽअद्यम् । च । भूत्वा । अभिऽपर्यावर्तन्त ॥ ४ ॥

ऐनं श्रद्धा गच्छत्यैनं यज्ञो गच्छत्यैनं[5] लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद ॥ ५ ॥

आ । एनम् । श्रद्धा । गच्छति । आ । एनम् । यज्ञः । गच्छति । आ । एनम् । लोकः[6] । गच्छति । आ । एनम् । अन्नम् । गच्छति । आ । एनम् । अन्नऽअद्यम् । गच्छति । यः ।० ॥ ५ ॥

प्रथमेनुवाके सप्तमं पर्यायसूक्तम् ॥

इति प्रथमोनुवाकः ॥

---

१ So we with all our authorities. Rw omit सः. २ So we with all our authorities. Rw change to गच्छन्ति. ३ S^m P लोकाश्चा°. ४ E भूत्वाभिप°. ५ S^m गंछत्यैनां. ६ P लोकाः ।.

सोऽरज्यत ततो राजन्योऽजायत ॥ १ ॥

सः । अरज्यत । ततः । राजन्यः । अजायत ॥ १ ॥

स विशः सबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत् ॥ २ ॥

सः । विशः । सऽबन्धून् । अन्नम् । अन्नऽअद्यम् । अभिऽउदतिष्ठत् ॥ २ ॥

विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥ ३ ॥

विशाम् । च । वै । सः । सऽबन्धूनाम् । च । अन्नस्य । च । अन्नऽअद्यस्य । च । प्रियम् । धाम । भवति । यः ।० ॥ ३ ॥

इति द्वितीयेऽनुवाके प्रथमं पर्यायसूक्तम् ॥

स विशोऽनु व्यचलत् ॥ १ ॥

सः । विशः । अनु । वि । अचलत् ॥ १ ॥

तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥ २ ॥

तम् । सभा । च । समऽइतिः । च । सेना । च । सुरा । च । अनुऽव्यचलन् ॥ २ ॥

सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥ ३ ॥

सभायाः । च । वै । सः । समऽइतेः । च । सेनायाः । च । सुरायाः । च । प्रियम् । धाम । भवति । यः । एवम् । वेद ॥ ३ ॥

इति द्वितीयेऽनुवाके द्वितीयं पर्यायसूक्तम् ॥

तद् यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहानागच्छेत् ॥ १ ॥

तत् । यस्य । एवम् । विद्वान् । व्रात्यः । राज्ञः । अतिथिः । गृहान् । आऽगच्छेत् ॥ १ ॥

श्रेयांसमेनमात्मनो मानयेत् तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥ २ ॥

---

१ B B[h] C E R P P[2] J सबन्धूनन्नाद्यं°. Cs सबंधूनन्नमन्नाद्यं. Cp अन्नं । अन्नऽअद्यं । changed to अन्नऽअद्यं ।, omitting अन्नं ।. We with A D K K[m] S[m] V Dc. २ P °चलत् ।. ३ All our MSS. and Vaidikas have °येतथा except Cp which has मानयेत् । तथा । changed from मानये । तथा ।.

श्रेयांसम् । एनम् । आत्मनः[1] । मानयेत्[2] । तथा । क्षत्राय । न । आ । वृश्चते । तथा । राष्ट्राय । न । आ । वृश्चते ॥ २ ॥

अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥ ३ ॥

अतः । वै । ब्रह्म । च । क्षत्रम् । च । उत् । अतिष्ठताम् । ते इति । अब्रूताम् । कम् । प्र । विशाव । इति ॥ ३ ॥

अतो[3] वै बृहस्पतिमेव ब्रह्म प्रा[4] विशत्विन्द्रं क्षत्रं तथा वा इति ॥ ४ ॥

०। बृहस्पतिम् । एव । ब्रह्म । प्र[4] । विशतु । इन्द्रम् । क्षत्रम् । तथा । वै । इति ॥ ४ ॥

अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥ ५ ॥

अतः । वै । बृहस्पतिम् । एव । ब्रह्म । प्र । अविशत् । इन्द्रम् । क्षत्रम् ॥ ५ ॥

इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥ ६ ॥

इयम् । वै । ऊं इति । पृथिवी । बृहस्पतिः । द्यौः । एव । इन्द्रः ॥ ६ ॥

अयं वा उ[5] अग्निर्ब्रह्मा[6]सावादित्यः क्षत्रम् ॥ ७ ॥

अयम् । वै । ऊं इति । अग्निः । ब्रह्म । असौ । आदित्यः । क्षत्रम् ॥ ७ ॥

ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ॥ ८ ॥

आ । एनम् । ब्रह्म । गच्छति । ब्रह्मऽवर्चसी । भवति ॥ ८ ॥

यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥ ९ ॥

यः । पृथिवीम् । बृहस्पतिम् । अग्निम् । ब्रह्म । वेद ॥ ९ ॥

ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति ॥ १० ॥

आ । एनम् । इन्द्रियम् । गच्छति । इन्द्रियऽवान् । भवति ॥ १० ॥

य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥ ११ ॥

यः । आदित्यम् । क्षत्रम् । दिवम् । इन्द्रम् । वेद ॥ ११ ॥

इति द्वितीयेऽनुवाके तृतीयं पर्यायसूक्तम् ॥

---

१ P आत्मानः ।. २ See note 3, page 333. ३ So we with A B B^h D K K^m S^m V Cs Cp. Rw omit अतो वै. C E R omit the words. Dc omits them at first but subsequently restores them. ४ B B^h Cs ब्रह्म प्रावि° (in all corrected from ब्रह्म प्रावि°). C R S^m ब्रह्म प्रावि°. Dc ब्रह्म प्राविश° changed to ब्रह्म प्राविश°. We with A D E K K^m V. P ब्रह्म । प्र॰विश° ।. P^2 ब्रह्म । प्र॰विशतु ।. J प्र॰विशतु । changed to प्र॰विशतु ।. Cp बह्म । प्र॰विशतु ।. ५ B E ऊं. ६ A B °ब्रह्मा°.

तद् य॒स्यै॒वं वि॒द्वान् व्रात्यो॑ऽतिथिर्गृ॒हाना॒गच्छे॑त् ॥ १ ॥

°व्रात्यः॑ । अति॑थिः ।० ॥ १ ॥

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रू॒याद् व्रात्य॒ क्वा॑वात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु व्रात्य॒ यथा॑ ते नि॒कामस्तथा॒स्त्विति॑ ॥ २ ॥

स्वय॑म् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒यात् । व्रात्य॑ । क्व॑ । अ॒वा॒त्सीः॒ । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वशः॑ । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒मः । तथा॑ । अ॒स्तु॒ । इति॑ ॥ २ ॥

यदे॑न॒माह॒ व्रात्य॒ क्वा॑वात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥ ३ ॥

यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । क्व॑ । अ॒वा॒त्सीः॒ । इति॑ । प॒थः । ए॒व । तेन॑ । दे॒व॒ऽयाना॑न्[1] । अव॑ । रु॒न्द्धे॒ ॥ ३ ॥

यदे॑न॒माह॒ व्रात्यो॑द॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥ ४ ॥

०। व्रात्य॑ । उ॒द॒कम् । इति॑ । अ॒पः । ए॒व । तेन॑ । अव॑ । रु॒न्द्धे॒ ॥ ४ ॥

यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥ ५ ॥

०। व्रात्य॑ । त॒र्पय॑न्तु । इति॑ । प्रा॒णम् । ए॒व । तेन॑ । वर्षी॑यांसम् । कु॒रु॒ते॒ ॥ ५ ॥

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ॥ ६ ॥

यत् । ए॒न॒म् । आह॑[2] । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । इति॑ । प्रि॒यम् । ए॒व । तेन॑ । अव॑ । रु॒न्द्धे॒ ॥ ६ ॥

ऐनं॑ प्रि॒यं ग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥ ७ ॥

आ । ए॒न॒म् । प्रि॒यम् । ग॒च्छ॒ति॒ । प्रि॒यः । प्रि॒यस्य॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥ ७ ॥

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ [3]वश॑मे॒व तेनाव॑ रुन्द्धे ॥ ८ ॥

०। [4]ते॒ । वशः॑ । तथा॑ । अ॒स्तु॒ । इति॑ । [3]वश॑म् । ए॒व ।० ॥ ८ ॥

---

१ P °याना॑म् ।. २ P आ॒हे॑ ।. ३ B C E R $\overset{m}{\text{S}}$ P J Cp °ति॑ व॒श॰. We with A $\overset{h}{\text{B}}$ D K $\overset{m}{\text{K}}$ V Cs $\overset{2}{\text{P}}$ and Dc which changes °ति॑ व॒श॒मे॒व to °ति॒ वश॑मे॒व. ४ P ते ।.

ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद ॥ ९ ॥

आ । एनम् । वशः । गच्छति । वशी । वशिनाम् । भवति ।० ॥ ९ ॥

यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्द्धे १०

यत् । एनम् । आह । व्रात्य । यथा । ते । निऽकामः । तथा । अस्तु । इति । निऽकामम् । एव । तेन । अव । रुन्द्धे ॥ १० ॥

ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद ॥ ११ ॥

आ । एनम् । निऽकामः । गच्छति । निऽकामे । निऽकामस्य । भवति । यः । एवम् । वेद ॥ ११ ॥

इति द्वितीयेऽनुवाके चतुर्थं पर्यायसूक्तम् ॥

तद् यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहानागच्छेत् ॥ १ ॥

०। व्रात्यः । उद्धृतेषु । अग्निषु । अधिऽश्रिते । अग्निऽहोत्रे । अतिथिः । गृहान् । आऽगच्छेत् ॥ १ ॥

स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्यातिसृज होष्यामीति ॥ २ ॥

स्वयम् । एनम् । अभिऽउदेत्य । ब्रूयात् । व्रात्य । अति । सृज । होष्यामि । इति ॥ २ ॥

स चातिसृजेज्जुहुयान्न चातिसृजेन्न जुहुयात् ॥ ३ ॥

सः । च । अतिऽसृजेत् । जुहुयात् । न । च । अतिऽसृजेत् । न । जुहुयात् ॥ ३ ॥

स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥ ४ ॥

सः । यः । एवम् । विदुषा । व्रात्येन । अतिऽसृष्टः । जुहोति ॥ ४ ॥

प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥ ५ ॥

---

१ A B B^h C D S^m ऐनं वशो ग°. E R एनं वशो ग°. K^m ऐनं वशो ग°. Cs ऐनं वशो ग°. P J एनम् । वशः । गच्छति ।. P^2 एनम् । वशः । गच्छति ।. Cp आ । एनं । वशः । ग° ।. K V ऐनं वशो. The weight of authority is certainly in favour of the antodâtta. २ P P^2 J omit आ ।. In those MSS. which omit the आ it is to be supplied from verse 7. We with Cp. ३ P एनम् ।. ४ A D K K^m V Cs P^2 जानाति. Dc जानाति changed to जानाति. We with B B^h C E R S^m P J Cp.

प्र । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । प्र । दे॒व॒ऽयान॑म् ॥ ५ ॥

न दे॒वेष्वा वृ॑श्च॒ते हु॒तम॑स्य भवति ॥ ६ ॥

न । दे॒वेषु॑ । आ । वृ॒श्च॒ते॒ । हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥ ६ ॥

पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒-
होति॑ ॥ ७ ॥

परि॑ । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । यः । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न ।
अति॑ऽसृष्टः । जु॒होति॑ ॥ ७ ॥

अथ॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ॥ ८ ॥

अथ॑ । यः । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसृष्टः । जु॒होति॑ ॥ ८ ॥

न पि॑तृ॒याणं॒ पन्था॑ जा॑नाति॒ न दे॑व॒यान॑म् ॥ ९ ॥

न । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । न । दे॒व॒ऽयान॑म् ॥ ९ ॥

आ दे॒वेषु॒ वृ॑श्च॒ते अहु॒तम॑स्य भवति ॥ १० ॥

आ । दे॒वेषु॑ । वृ॒श्च॒ते॒ । अहु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥ १० ॥

नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒-
होति॑ ॥ ११ ॥

न । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । यः । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न ।
अन॑तिऽसृष्टः । जु॒होति॑ ॥ ११ ॥

इति द्वितीयेनुवाके पञ्चमं पर्यायसूक्तम् ॥

तद् य॒स्यैवं वि॒द्वान् व्रात्य॒ एका॑ं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥ १ ॥

०। व्रात्य॑ः । एका॑म् । रात्रि॑म् । अति॑थिः । गृ॒हे । वस॑ति ॥ १ ॥

ये पृ॑थि॒व्यां पुण्या॑ लो॒कास्ता॒ने॒व तेनाव॑ रुन्द्धे ॥ २ ॥

ये । पृ॒थि॒व्याम् । पुण्या॑ः । लो॒काः । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्द्धे॒ ॥ २ ॥

तद् य॒स्यैवं वि॒द्वान् व्रात्यो॑ द्वि॒तीया॒ं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥ ३ ॥

०। व्रात्य॑ः । द्वि॒तीया॑म् । रात्रि॑म् ।०। ॥ ३ ॥

---

१ P P[2] पथाम् ।. We with J Cp. २ See note 4, page 336. ३ B[h] K वृश्चतेहु॰. We with A B C D E K[m] R S[m] V Dc Cs. ४ P विदुषः ।.

ये ऽन्तरिक्षे पुण्या लोकास्तानेव तेनाव रुन्द्धे ॥ ४ ॥

ये । अन्तरिक्षे । पुण्याः ।० ॥ ४ ॥

तद् यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ॥ ५ ॥

०। व्रात्यः । तृतीयाम् । रात्रिम् ।० ॥ ५ ॥

ये दिवि पुण्या लोकास्तानेव तेनाव रुन्द्धे ॥ ६ ॥

ये । दिवि । पुण्याः ।० ॥ ६ ॥

तद् यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ॥ ७ ॥

०। व्रात्यः । चतुर्थीम् । रात्रिम् । अतिथिः ।० ॥ ७ ॥

ये पुण्यानां पुण्या लोकास्तानेव तेनाव रुन्द्धे ॥ ८ ॥

ये । पुण्यानाम् । पुण्याः ।० ॥ ८ ॥

तद् यस्यैवं विद्वान् व्रात्योपरिमिता रात्रीरतिथिर्गृहे वसति ॥ ९ ॥

तत् । यस्य । एवम् । विद्वान् । व्रात्यः । अपरिऽमिताः । रात्रीः । अतिथिः । गृहे । वसति ॥ ९ ॥

य एवापरिमिताः पुण्या लोकास्तानेव तेनाव रुन्द्धे ॥ १० ॥

ये । एव । अपरिऽमिताः । पुण्याः । लोकाः । तान् । एव । तेन । अव । रुन्द्धे ॥ १० ॥

अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहानागच्छेत् ॥ ११ ॥

अथ । यस्य । अव्रात्यः । व्रात्यऽब्रुवः । नामऽबिभ्रती । अतिथिः । गृहान् । आऽगच्छेत् ॥ ११ ॥

कर्षेदेनं न चैनं कर्षेत् ॥ १२ ॥

कर्षेत् । एनम् । न । च । एनम् । कर्षेत् ॥ १२ ॥

अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवता परि वेवेष्मीत्येनं परि वेविष्यात् ॥ १३ ॥

अस्यै । देवतायै । उदकम् । याचामि । इमाम् । देवताम् । वासये । इमाम् । इमाम् । देवताम् । परि । वेवेष्मि । इति । एनम् । परि । वेविष्यात् ॥ १३ ॥

तस्यामेवास्य तद् देवतायां हुतं भवति य एवं वेद ॥ १४ ॥

---

१ C यंत°. ABDKK^mS^mVDc Cs ये अन्त°. We with B^hER. २ P °रि°।. ३ P रात्रिः।. ४ J वेवेष्मि।.

तस्याम् । एव । अस्य । तत् । देवतायाम् । हुतम् । भवति । यः । एवम् । वेद ॥ १४ ॥

इति द्वितीयेनुवाके षष्ठं पर्यायसूक्तम् ॥

स यत् प्राचीं दिशमनु व्यचलन्मारुतं शर्धो भूत्वानुव्यचलन्मनो[1]न्नादं कृत्वा ॥ १ ॥

सः । यत् । प्राचीम् । दिशम् । अनु । विऽअचलत् । मारुतम् । शर्धः । भूत्वा । अनुऽव्यचिलत् । मनः । अन्नऽअदम् । कृत्वा ॥ १ ॥

मनसान्नादेनान्नमत्ति य एवं वेद ॥ २ ॥

मनसा । अन्नऽअदेन[2] । अन्नम् । अत्ति । यः ।० ॥ २ ॥

स यद् दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद् बलमन्नादं कृत्वा ॥ ३ ॥

०। यत् । दक्षिणाम् । दिशम् । अनु । वि[3]ऽअचलत् । इन्द्रः । भूत्वा । अनुऽव्यचलत् । बलम् । अन्नऽअदम् । कृत्वा ॥ ३ ॥

बलेनान्नादेनान्नमत्ति य एवं वेद ॥ ४ ॥

बलेन । अन्नऽअदेन । अन्नम् ।० ॥ ४ ॥

स यत् प्रतीचीं दिशमनु व्यचलद् वरुणो राजा भूत्वानुव्यचलदपो[4]न्नादीः कृत्वा ॥ ५ ॥

०। यत् । प्रतीचीम् । दिशम्[5] । अनु । विऽअचलत् । वरुणः । राजा । भूत्वा । अनुऽव्यचिलत् । अपः । अन्नऽअदीः । कृत्वा ॥ ५ ॥

अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥ ६ ॥

अत्ऽभिः । अन्नऽअदीभिः । अन्नम् ।० ॥ ६ ॥

स यदुदीचीं दिशमनु व्यचलत् सोमो राजा भूत्वानुव्यचलत् सप्तर्षि[6]भिर्हुत आहुतिमन्नादीं कृत्वा ॥ ७ ॥

०। यत् । उदीचीम् । दिशम् । अनु । विऽअचलत् । सोमः । राजा । भूत्वा । अनुऽव्यचिलत् । सप्तर्षिऽभिः । हुते । आऽहुतिम् । अन्नऽअदीम् । कृत्वा ॥ ७ ॥

---

१ E °नो°. २ P °अदनं ।. ३ P वि° ।. ४ A B C E K K^m R °दपो°. Dc °दपो° changed to °दपो°. We with B^h D S^m V Cs. ५ P दिशिम् ।. ६ A K °सप्तऋषि°.

आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥ ८ ॥

आऽहुत्या । अन्नऽअद्या । अन्नम् ।० ॥ ८ ॥

स यद् ध्रुवां दिशमनु व्यचलद् विष्णुर्भूत्वानुव्यचलद् विराजमन्नादीं कृत्वा ॥ ९ ॥

०। यत् । ध्रुवाम् । दिशम् । अनु । विऽअचलत् । विष्णुः । भूत्वा । अनुऽव्यचलत् । विऽराजम् । अन्नऽअदीम् । कृत्वा ॥ ९ ॥

विराजान्नाद्यान्नमत्ति य एवं वेद ॥ १० ॥

विऽराजा । अन्नऽअद्या । अन्नम् ।० ॥ १० ॥

स यत् पशूननु व्यचलद् रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥११॥

०। यत् । पशून् । अनु । विऽअचलत् । रुद्रः । भूत्वा । अनुऽव्यचलत् । ओषधीः । अन्नऽअदीः । कृत्वा ॥ ११ ॥

ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥ १२ ॥

ओषधीभिः । अन्नऽअदीभिः । अन्नम् ।० ॥ १२ ॥

स यत् पितॄननु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारमन्नादं कृत्वा ॥ १३ ॥

०। यत् । पितॄन् । अनु । विऽअचलत् । यमः । राजा । भूत्वा । अनुऽव्यचलत् । स्वधाऽकारम् । अन्नऽअदम् । कृत्वा ॥ १३ ॥

स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥ १४ ॥

स्वधाऽकारेण । अन्नऽअदेन । अन्नम् ।० ॥ १४ ॥

स यन्मनुष्या३नन्नु व्यचलदग्निर्भूत्वानुव्यचलत् स्वाहाकारमन्नादं कृत्वा ॥ १५ ॥

०। यत् । मनुष्यान् । अनु । विऽअचलत् । अग्निः । भूत्वा । अनुऽव्यचलत् । स्वाहाऽकारम् । अन्नऽअदम् ।० ॥ १५ ॥

स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥ १६ ॥

स्वाहाऽकारेण । अन्नऽअदेन ।० ॥ १६ ॥

स यदूर्ध्वां दिशमनु व्यचलद् बृहस्पतिर्भूत्वानुव्यचलद् वषट्कारमन्नादं कृत्वा ॥ १७ ॥

०। यत्। ऊर्ध्वाम्। दिशम्। अनु। विऽअचलत्। बृहस्पतिः। भूत्वा। अनुऽव्यचलत्। वषट्ऽकारम्। अन्नऽअदम्।०॥ १७॥

वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥ १८ ॥

वषट्ऽकारेण। अन्नऽअदेन।०॥ १८॥

स यद् देवाननु व्यचलदीशानो भूत्वानुव्यचलन्मन्युमन्नादं कृत्वा ॥१९॥

०। यत्। देवान्। अनु। विऽअचलत्। ईशानः। भूत्वा। अनुऽव्यचलत्। मन्युम्। अन्नऽअदम्।०॥ १९॥

मन्युनान्नादेनान्नमत्ति य एवं वेद ॥ २० ॥

मन्युना। अन्नऽअदेन।०॥ २०॥

स यत् प्रजा अनु व्यचलत् प्रजापतिर्भूत्वानुव्यचलत् प्राणमन्नादं कृत्वा ॥ २१ ॥

०। यत्। प्रऽजाः। अनु। विऽअचलत्। प्रजाऽपतिः। भूत्वा। अनुऽव्यचलत्। प्राणम्। अन्नऽअदम्।०॥ २१॥

प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥ २२ ॥

प्राणेन। अन्नऽअदेन।०॥ २२॥

स यत् सर्वानन्तर्देशाननु व्यचलत् परमेष्ठी भूत्वानुव्यचलद् ब्रह्मान्नादं कृत्वा ॥ २३ ॥

सः। यत्। सर्वान्। अन्तःऽदेशान्। अनु। विऽअचलत्। परमेऽस्थी। भूत्वा। अनुऽव्यचलत्। ब्रह्म। अन्नऽअदम्। कृत्वा॥ २३॥

ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥ २४ ॥

ब्रह्मणा। अन्नऽअदेन। अन्नम्। अत्ति। यः। एवम्। वेद॥ २४॥

इति द्वितीयेनुवाके सप्तमं पर्यायसूक्तम्॥

तस्य व्रात्यस्य ॥ १ ॥

तस्य। व्रात्यस्य॥ १॥

सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥ २ ॥

सप्त । प्राणाः । सप्त । अपानाः । सप्त । विऽआनाः ॥ २ ॥

तस्य[1] व्रात्यस्य । योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥ ३ ॥

०। यः । अस्य । प्रथमः । प्राणः । ऊर्ध्वः । नाम । अयम् । सः । अग्निः ॥ ३ ॥

तस्य[1] व्रात्यस्य । योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥ ४॥

०। अस्य । द्वितीयः । प्राणः । प्रऽऊढः । नाम । असौ । सः । आदित्यः ॥ ४ ॥

तस्य व्रात्यस्य । योऽस्य तृतीयः प्राणोऽभ्यूढो[2] नामासौ स चन्द्रमाः ॥ ५॥

०। अस्य । तृतीयः । प्राणः । अभिऽऊढः[3] । नाम । असौ । सः । चन्द्रमाः ॥ ५ ॥

तस्य व्रात्यस्य । योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥ ६ ॥

०। अस्य । चतुर्थः । प्राणः । विऽभूः । नाम । अयम् । सः । पवमानः ॥ ६ ॥

तस्य व्रात्यस्य । योऽस्य पञ्चमः प्राणो योनिर्नाम[4] ता इमा आपः ॥ ७ ॥

०। अस्य । पञ्चमः । प्राणः । योनिः । नाम । ताः । इमाः । आपः ॥ ७ ॥

तस्य व्रात्यस्य । योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥ ८ ॥

अस्य । षष्ठः । प्राणः । प्रियः । नाम । ते[5] । इमे । पशवः[6] ॥ ८ ॥

तस्य व्रात्यस्य । योऽस्य सप्तमः प्राणोऽपरिमितो[7] नाम ता इमाः प्रजाः ॥ ९॥

०। अस्य । सप्तमः । प्राणः । अपरिऽमितः । नाम । ताः । इमाः । प्रऽजाः ॥ ९ ॥

इति द्वितीयेऽनुवाके अष्टमं पर्यायसूक्तम् ॥

तस्य व्रात्यस्य । योऽस्य प्रथमोऽपानः[8] सा पौर्णमासी ॥ १ ॥

०। प्रथमः । अपानः । सा । पौर्णऽमासी ॥ १ ॥

तस्य व्रात्यस्य । योऽस्य द्वितीयोऽपानः साष्टका ॥ २ ॥

०। द्वितीयः । अपानः । सा । अष्टका ॥ २ ॥

तस्य व्रात्यस्य । योऽस्य तृतीयोऽपानः सामावास्या ॥ ३ ॥

०। तृतीयः । अपानः । सा । अमाऽवास्या ॥ ३ ॥

---

१ So we with all our authorities. See **R**w. २ **A B̊ C D E R S̊ C**s °भ्यूढो. We with **K K̊ V** and **D**c, the last changing °भ्यूढो to °भ्यूंढो. ३ **P J C**p अभिऽऊढः ।. We with **P̊**. ४ **D** योनिर्णाम. ५ **P** ते ।. ६ **P** पश्वः ।. ७ **B** °मितौ. ८ **A B̊ R** प्रथमोपानः. **C** °थमोपानः.

तस्य व्रात्यस्य । योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥ ४ ॥

०। चतुर्थः । अपानः । सा । श्रद्धा ॥ ४ ॥

तस्य व्रात्यस्य । योऽस्य पञ्चमोऽपानः सा दीक्षा ॥ ५ ॥

०। पञ्चमः । अपानः । सा । दीक्षा ॥ ५ ॥

तस्य व्रात्यस्य । योऽस्य षष्ठोऽपानः स यज्ञः ॥ ६ ॥

०। षष्ठः । अपानः । सः । यज्ञः ॥ ६ ॥

तस्य व्रात्यस्य । योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥ ७ ॥

सप्तमः । अपानः । ताः । इमाः । दक्षिणाः ॥ ७ ॥

इति द्वितीयेऽनुवाके नवमं पर्यायसूक्तम् ॥

तस्य व्रात्यस्य । योऽस्य प्रथमो व्यानः सेयं भूमिः ॥ १ ॥

०। अस्य । प्रथमः । विऽआनः । सा । इयम् । भूमिः ॥ १ ॥

तस्य व्रात्यस्य । योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥ २ ॥

०। अस्य । द्वितीयः । विऽआनः । तत् । अन्तरिक्षम् ॥ २ ॥

तस्य व्रात्यस्य । योऽस्य तृतीयो व्यानः सा द्यौः ॥ ३ ॥

०। अस्य । तृतीयः । विऽआनः । सा । द्यौः ॥ ३ ॥

तस्य व्रात्यस्य । योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥ ४ ॥

०। अस्य । चतुर्थः । विऽआनः । तानि । नक्षत्राणि ॥ ४ ॥

तस्य व्रात्यस्य । योऽस्य पञ्चमो व्यानस्त ऋतवः ॥ ५ ॥

०। अस्य । पञ्चमः । विऽआनः । ते । ऋतवः ॥ ५ ॥

तस्य व्रात्यस्य । योऽस्य षष्ठो व्यानस्त आर्तवाः ॥ ६ ॥

०। अस्य । षष्ठः । विऽआनः । ते । आर्तवाः ॥ ६ ॥

तस्य व्रात्यस्य । योऽस्य सप्तमो व्यानः स संवत्सरः ॥ ७ ॥

०। यः । अस्य । सप्तमः । विऽआनः । सः । सम्ऽवत्सरः ॥ ७ ॥

---

१ C R चतुर्थो°. २ A B B C R पञ्चमो°. We with D E K K S V Dc Cs. ३ A B C K K R षष्ठो°. We with D E K S V Dc Cs. ४ A B B C K R सप्तमो°. We with D E K S V Dc Cs. ५ P ते । आर्तवः ।.

तस्य व्रात्यस्य । समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोनु-
परियन्ति व्रात्यं च ॥ ८ ॥

समानम् । अर्थम् । परि । यन्ति । देवाः । सम्ऽवत्सरम् । वै । एतत् । ऋतवः । अनुऽप-
रियन्ति । व्रात्यम् । च ॥ ८ ॥

तस्य व्रात्यस्य । यदादित्यमभिसंविशन्त्यमावास्यां[1] चैव तत्पौर्णमासीं च ॥ ९ ॥

०। यत् । आदित्यम् । अभिऽसंविशन्ति । अमाऽवास्याम् । च । एव । तत् । पौर्णऽमा-
सीम् । च ॥ ९ ॥

तस्य व्रात्यस्य । एकं तदेषाममृतत्वमित्याहुतिरेव[2] ॥ १० ॥

एकम् । तत् । एषाम् । अमृतऽत्वम् । इति । आऽहुतिः । एव ॥ १० ॥

इति द्वितीयेनुवाके दशमं पर्यायसूक्तम् ॥

तस्य व्रात्यस्य ॥ १ ॥

तस्य । व्रात्यस्य ॥ १ ॥

यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥ २ ॥

यत् । अस्य । दक्षिणम् । अक्षि । असौ । सः । आदित्यः । यत् । अस्य । सव्यम् । अक्षि ।
असौ । सः । चन्द्रमाः ॥ २ ॥

योस्य दक्षिणः कर्णोयं सो अग्निर्योस्य सव्यः कर्णोयं स पवमानः ॥ ३ ॥

यः । अस्य । दक्षिणः । कर्णः । अयम् । सः । अग्निः । यः । अस्य । सव्यः । कर्णः । अ-
यम् । सः । पवमानः ॥ ३ ॥

अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥ ४ ॥

अहोरात्रे इति । नासिके इति । दितिः । च । अदितिः । च । शीर्षकपाले इति शीर्षऽक-
पाले । सम्ऽवत्सरः । शिरः ॥ ४ ॥

अह्ना प्रत्यङ् व्रात्यो रात्र्या प्राङ् नमो व्रात्याय ॥ ५ ॥

अह्ना । प्रत्यङ् । व्रात्यः । रात्र्या । प्राङ् । नमः । व्रात्याय ॥ ५ ॥

द्वितीयेनुवाक एकादशं पर्यायसूक्तम् ॥

द्वितीयोनुवाकः ॥

इति पञ्चदशं काण्डं समाप्तम् ॥

---

१ A B B^h C R P Cp °वास्यां. We with D E K K^m S^m V Dc Cs P^2 J. २ B^h C D E R S^m Cs P J Cp तदेषा°. We with K K^m V Dc P^2.

कतिषुचित् कर्मसु शान्त्युदकं विहितम् । तेन हि आचमनप्रोक्षणावसेचनासेचनाप्लावनानि कर्तव्यानि भवन्ति । तच्छान्त्युदकं कतिभिश्चिच्छान्तिनामकैः सूक्तैः कर्तव्यं भवति । तत् कांसपात्रे कर्तव्यम् । तथाकरणात्पूर्वम् "अतिसृष्टो अपां वृषभः" इति सूक्तेन अपोतिसृज्य अवकरं विसर्जयति । कांसपात्रे अपोवसिच्य ताभिस्तन्मध्यगतं मलं निर्गमयतीत्यर्थः । इति सांप्रदायिकाः । सूत्रितं हि । "अतिसृष्टो अपां वृषभ इत्यपोतिसृज्य" इति [कौ° १.९] ॥

अतिसृष्टो अपां वृषभोतिसृष्टा अग्नयो दिव्याः ॥ १ ॥

अतिऽसृष्टः । अपाम् । वृषभः । अतिऽसृष्टाः । अग्नयः । दिव्याः ॥ १ ॥

रुजन् परिरुजन् मृणन् प्रमृणन् ॥ २ ॥

रुजन् । परिऽरुजन् । मृणन् । प्रऽमृणन् ॥ २ ॥

म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥ ३ ॥

म्रोकः । मनःऽहा । खनः । निःऽदाहः[1] । आत्मऽदूषिः । तनूऽदूषिः ॥ ३ ॥

इदं तमति सृजामि तं माभ्यवनिक्षि ॥ ४ ॥

इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि ॥ ४ ॥

तेन तमभ्यतिसृजामो यो३[2]स्मान् द्वेष्टि यं वयं द्विष्मः ॥ ५ ॥

तेन । तम् । अभिऽअतिसृजामः । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ॥ ५ ॥

अपामग्रमसि समुद्रं वोभ्यवसृजामि ॥ ६ ॥

अपाम् । अग्रम् । असि । समुद्रम् । वः । अभिऽअवसृजामि ॥ ६ ॥

यो३[3]प्स्वं१ग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥ ७ ॥

यः । अप्ऽसु । अग्निः । अति । तम्[4] । सृजामि । म्रोकम् । खनिम् । तनूऽदूषिम् ॥ ७ ॥

यो व आपोग्निराविवेश स एष यद् वो घोरं तदेतत् ॥ ८ ॥

यः । वः । आपः । अग्निः । आऽविवेश । सः । एषः । यत् । वः । घोरम् । तत् । एतत् ॥ ८ ॥

इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत् ॥ ९ ॥

---

१ P °हाः ।. २ C D K V १ for ३. We with B^{h} E K^{m} R S^{m} Dc Cs. ३ B C K V १ for ३. We with B^{h} D E K^{m} R S^{m} Dc Cs. ४ P^{2} तत् ।.

इन्द्रस्य । वः । इन्द्रियेण । अभि । सिञ्चेत् ॥ ९ ॥

अरिप्रा आपो अप रिप्रमस्मत् ॥ १० ॥

अरिप्राः । आपः । अप । रिप्रम् । अस्मत् ॥ १० ॥

प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥ ११ ॥

प्र । अस्मत् । एनः । वहन्तु । प्र । दुःऽस्वप्न्यम् । वहन्तु ॥ ११ ॥

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥ १२ ॥

शिवेन । मा । चक्षुषा । पश्यत । आपः । शिवया । तन्वा । उप । स्पृशत । त्वचम् । मे ॥ १२ ॥

शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥ १३ ॥

शिवान् । अग्नीन् । अप्सुऽसदः । हवामहे । मयि । क्षत्रम् । वर्चः । आ । धत्त । देवीः[1] ॥ १३ ॥

इति प्रथमेनुवाके प्रथमं पर्यायसूक्तम् ॥

मरणं व्यसनं चैव बन्धनं च विशेषतः ।
प्रणिपातोन्मत्तता वा दैवोपहतिरेव च ।
पुत्रादिधननाशश्च गृहे दोषान् बहूनपि ।

एतानि सर्वाणि कानिचिद्वा तेषां मध्ये यथा शत्रोर्भवन्ति तथोद्देशेन यत् कर्म तद् अभिचारकर्म । एतन्नामकः कर्मविशेषः । तादृशस्याभिचारकर्मणः समाप्तौ अवभृथं स्नात्वा "निर्दुरर्मण्यः" इति सूक्तेन सर्वौषधिभिर्नाम कैश्चिदोषधिविशेषैरात्मानम् अभिमृशति । तद् उक्तं कौशिकेन । "निर्दुरर्मण्य इति संधाव्याभिमृशति" इति [कौ° ६. ३] ॥ अभिचारं कृत्वा कर्ता शान्तिमिमां करोतीत्यर्थः ॥

तथा उपनयनकर्मणि अनेन सूक्तेन कुङ्कुमचन्दनसर्वौषध्यादिना शरीरं समालभ्य आत्मानम् अभिमन्त्रयत आयुष्कामः । सूत्रितं हि । "निर्दुरर्मण्य इति संधाव्य" इति [कौ° ७. ९] ॥

तथा चक्षुरादीन्द्रियदार्ढ्यकामः अरण्ये गत्वा अनेन सूक्तेन सर्वौषधिम् अभिमन्त्र्य अनुलोमं प्रलिम्पति । तथा च सूत्रम् । "निर्दुरर्मण्य इति सर्वसुरभिचूर्णैररण्येऽप्रतीहारं प्रलिम्पति" इति [कौ° ७. ९] ॥

श्रोत्रं वाग् मनश्चक्षुर्दन्ता नासिका अन्यच्च सर्वं विकलेन्द्रियं दृढं भवति । यो विकलेन्द्रियस्तस्येदं कर्म ॥

निर्दुरर्मण्य ऊर्जा मधुमती वाक् ॥ १ ॥

निः । दुःऽअर्मण्यः । ऊर्जा[2] । मधुऽमती । वाक् ॥ १ ॥

मधुमती[3] स्थ मधुमतीं वाचमुदेयम् ॥ २ ॥

मधुऽमतीः[4] । स्थ । मधुऽमतीम् । वाचम् । उदेयम् ॥ २ ॥

---

१ P² देवीः ।. २ None of our authorities have ऊर्जाः ।. ३ Bʰ मधुमतीः. ४ P P² J मधुऽमती ।. J once had the visarga, but has subsequently removed it. We with Cp.

उप॑हूतो मे गो॒पा उप॑हूतो गोपी॒थः ॥ ३ ॥

उप॑ऽहूतः । मे॒ । गो॒पाः । उप॑ऽहूतः[1] । गो॒पी॒थः ॥ ३ ॥

सु॒श्रुतौ॒ कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम् ॥ ४ ॥

सु॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्र॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्रम् । श्लोक॑म् । श्रू॒या॒स॒म् ॥ ४ ॥

सु॒श्रु॑तिश्च॒ मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥ ५ ॥

सु॒ऽश्रु॑तिः[2] । च॒ । मा॒ । उप॑ऽश्रुतिः । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षुः॑ । अज॑स्रम् ।

ज्योतिः॑ ॥ ५ ॥

ऋषी॑णां प्रस्त॒रो॑ऽसि[3] नमो॑ऽस्तु दैवा॑य प्रस्तरा॑य ॥ ६ ॥

ऋषी॑णाम् । प्र॒ऽस्त॒रः । अ॒सि॒ । नमः॑ । अ॒स्तु॒ । दैवा॑य । प्र॒ऽस्त॒राय॑ ॥ ६ ॥

इति प्रथमेनुवाके द्वितीयं पर्यायसूक्तम् ॥

उपनयने "मूर्धाहं" "नाभिरहम्" इति सूक्ताभ्याम् आयुरभिवृद्ध्यर्थं माणवक उद्यन्तम् आदित्यम् उपतिष्ठते । तद् उक्तं कौशिकेन । "मूर्धाहम् [१६.३] विषासहिम् [१७.१] इत्युद्यन्तम् उपतिष्ठते" इत्यादि [कौ° ७.९] ॥

मू॒र्धाहं र॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम् ॥ १ ॥

मू॒र्धा । अ॒हम् । र॒यी॒णाम् । मू॒र्धा । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥ १ ॥

रु॒जश्च॑ मा वे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ॥ २ ॥

रु॒जः । च॒ । मा॒ । वे॒नः । च॒ । मा॒ । हा॒सि॒ष्टा॒म् । मू॒र्धा । च॒ । मा॒ । वि॒ऽध॑र्मा । च॒ । मा॒[4] ।

हा॒सि॒ष्टा॒म् ॥ २ ॥

उ॒र्वश्च॑ मा चम॒सश्च॒ मा हा॑सिष्टां ध॒र्ता च॑ मा ध॒रुण॑श्च॒ मा हा॑सिष्टाम् ॥ ३ ॥

उ॒र्वः । च॒ । मा॒ । च॒म॒सः । च॒ । मा॒[4] । हा॒सि॒ष्टा॒म् । ध॒र्ता । च॒ । मा॒ । ध॒रुणः॑ । च॒ । ० ॥ ३ ॥

वि॒मो॒कश्च॑ मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च॑[5] मा मात॒रिश्वा॑ च॒ मा

हा॑सिष्टाम् ॥ ४ ॥

वि॒ऽमो॒कः । च॒ । मा॒ । आ॒र्द्रऽप॑विः । च॒ । मा । हा॒सि॒ष्टा॒म् । आ॒र्द्रऽदा॑नुः । च॒ । मा॒ । मा॒-

त॒रिश्वा॑ । च॒ । मा । हा॒सि॒ष्टा॒म् ॥ ४ ॥

बृह॒स्पति॑र्म आ॒त्मा नृ॒मणा॒ नाम॒ हृद्यः॑ ॥ ५ ॥

---

१ Cp °हु° ।. We with P $\overset{2}{\text{P}}$ J. २ P सुश्रु॑तिः ।. ३ R $\overset{m}{\text{S}}$ Cs प्रस्त॒रो°. We with A $\overset{h}{\text{B}}$ C D E K $\overset{m}{\text{K}}$ V Dc. ४ P मा॒ ।. ५ R $\overset{m}{\text{S}}$ °दा॑नुश्च॒.

बृहस्पतिः । मे । आत्मा । नृऽमनाः । नाम । हृद्यः ॥ ५ ॥

असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥ ६ ॥

असम्ऽतापम् । मे । हृदयम् । उर्वी । गव्यूतिः । समुद्रः । अस्मि । विऽधर्मणा ॥ ६ ॥

इति प्रथमेनुवाके तृतीयं पर्यायसूक्तम् ॥

"नाभिरहम्" इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ॥

नाभिरहं रयीणां नाभिः समानानां भूयासम ॥ १ ॥

नाभिः । अहम् । रयीणाम् । नाभिः । समानानाम् । भूयासम् ॥ १ ॥

स्वासदसि सूषा अमृतो मर्त्येष्वा ॥ २ ॥

सुऽआसत् । असि । सुऽउषाः । अमृतः । मर्त्येषु । आ ॥ २ ॥

मा मां प्राणो हासीन्मो अपानोवहाय परा गात् ॥ ३ ॥

मा । माम् । प्राणः । हासीत् । मो इति । अपानः । अवऽहाय । परा । गात् ॥ ३ ॥

सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद् यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥ ४ ॥

सूर्यः । मा । अह्नः । पातु । अग्निः । पृथिव्याः । वायुः । अन्तरिक्षात् । यमः । मनुष्येभ्यः । सरस्वती । पार्थिवेभ्यः ॥ ४ ॥

प्राणापानौ मा मा हासिष्टं मा जने प्र मेषि ॥ ५ ॥

प्राणापानौ । मा । मा । हासिष्टम् । मा । जने । प्र । मेषि ॥ ५ ॥

स्वस्त्यं१द्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥ ६ ॥

स्वस्ति । अद्य । उषसः । दोषसः । च । सर्वः । आपः । सर्वऽगणः । अशीय ॥ ६ ॥

शर्करी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥ ७ ॥

---

१ P J °मनां ।. २ K पूषा. E षूषा. ३ A B C E R Cs P J Cp मां. We with D K K S V Dc P. ४ A B C E K R °नोवहाय. We with D K S V Dc Cs. ५ P मा ।. ६ A B C D E R S Dc Cs °स्त्य३° for °स्त्यं१°. K K V °स्त्या३°. ७ A D E R Cs °द्यो° (which means '१). C K १. P Cp अद्य ।. We with K S V Dc. ८ P आपः ।. ९ P आशीय ।. १० B B शर्करीः.

शार्करीः। स्थ। पशवः। मा। उप। स्थेषुः। मित्रावरुणौ। मे। प्राणापानौ। अग्निः। मे। दक्षम्। दधातु ॥ ७ ॥

प्रथमेनुवाके चतुर्थं पर्यायसूक्तम् ॥

इति प्रथमोनुवाकः ॥

दुःस्वप्नदर्शने शान्तावेतत् पर्यायसूक्तं विनियुज्यते। तद्यथा। "विद्म ते स्वप्न" इत्येकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि ॥
तथा अतिघोरं दुःस्वप्नं दृष्ट्वा अनेन सूक्तेन मैश्रधान्यं पुरोडाशं जुहोति ॥
तथा "विद्म ते स्वप्न" इति सूक्तेन दुःस्वप्नं दृष्ट्वा पार्श्वेन द्वितीयेन भूयते। येन पार्श्वेन दुःस्वप्नो दृष्टस्ततोन्येन पार्श्वेन शेत इत्यर्थः ॥
तथा अनेन सूक्तेन अन्नं स्वप्ने दृष्ट्वा निरीक्षते ॥
तद् उक्तं कौशिकेन। "विद्म ते स्वप्नेति सर्वेषाम् अप्ययः" इति [कौ॰५.१०] ॥

विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोसि यमस्य करणः ॥ १ ॥

विद्म। ते। स्वप्न। जनित्रम्। ग्राह्याः। पुत्रः। असि। यमस्य। करणः ॥ १ ॥

अन्तकोसि मृत्युरसि ॥ २ ॥

अन्तकः। असि। मृत्युः। असि ॥ २ ॥

तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ३ ॥

तम्। त्वा। स्वप्न। तथा। सम्। विद्म। सः। नः। स्वप्न। दुःऽस्वप्न्यात्। पाहि ॥ ३ ॥

विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोसि यमस्य करणः ।०।० ॥ ४ ॥

०। जनित्रम्। निःऽऋत्याः। पुत्रः।० ॥ ४ ॥

विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोसि ०।०।० ॥ ५ ॥

०। जनित्रम्। अभूत्याः। पुत्रः।० ॥ ५ ॥

विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोसि ०।०।० ॥ ६ ॥

०। जनित्रम्। निःऽभूत्याः। पुत्रः।० ॥ ६ ॥

विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोसि ०।०।० ॥ ७ ॥

०। जनित्रम्। पराऽभूत्याः। पुत्रः।० ॥ ७ ॥

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोसि यमस्य करणः ॥ ८ ॥

---

१ P P J स्थेषु। We with Cp. २ A B B E R Dc Cs दुःष्व॰. We with C D K K S V.

विद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्रः । असि । यमस्य । करणः ॥ ८ ॥

अन्तकोसि मृत्युरसि ॥ ९ ॥

अन्तकः । असि । मृत्युः । असि ॥ ९ ॥

तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ १० ॥

तम् । त्वा । स्वप्न । तथा । सम् । विद्म । सः । नः । स्वप्न । दुःऽस्वप्न्यात् । पाहि ॥ १० ॥

इति द्वितीयेनुवाके प्रथमं पर्यायसूक्तम् ॥

अभिचारकर्मणि "अजैष्म" इत्यादिपर्यायसूक्तचतुष्टयेन शत्रुषु पाशान् बद्धाभिमन्त्र्य निखनति ॥

तथा तत्रैव कर्मणि अनेन पर्यायचतुष्टयेन "अगन्म स्वः" इति अवसानद्वयवर्जितेन पदेपदे पाशान् वृश्चति ॥

तथा तत्रैव कर्मणि अनेन अवसानद्वयवर्जितेन अधिपाशान् बाधकान् शङ्कून् संक्षुद्य भ्राष्ट्रेभ्यस्यति ॥

तथा तत्रैव कर्मणि एतैश्चतुर्भिः पर्यायैः "अगन्म स्वः" इत्यवसानद्वयवर्जितै रक्तशालिक्षीरौदनम् अभिमन्त्र्य ददाति ॥

तथा तत्रैव कर्मणि उक्तैरेव पर्यायैर्वृषभं संपातवन्तं कृत्वा शत्रुगृहान् अभि सृजति ॥

तथा तत्रैव कर्मणि उक्तैः पर्यायैर्गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातान् आनयति ॥

सूत्रितं हि "अजैष्मेत्यधिपाशान् आदधाति । पदेपदे पाशान् वृश्चति । अधिपाशान् बाधकां छङ्कूंस्तान् संक्षुद्य संनह्य भ्राष्ट्रेभ्यस्यति । अशिशिषोः क्षीरौदनादीनि त्रीणि । गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातान् अभ्यतिनयति" इति [कौ° ६.३] ॥

"अगन्म स्वः" इत्यवसानद्वयेन आदित्यम् ईक्षते सर्वेषु तन्त्रेषु । तदुक्तं कौशिकेन । "अगन्म स्वरित्यादित्यमीक्षते" इति [कौ° १.६] ॥

अजैष्माद्यासनामाद्याभूमानागसो वयम् ॥ १ ॥

अजैष्म । अद्य । असनाम । अद्य । अभूम । अनागसः । वयम् ॥ १ ॥

उषो यस्माद् दुष्वप्न्यादभैष्माप तदुच्छतु ॥ २ ॥

उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु ॥ २ ॥

द्विषते तत् परा वह शपते तत् परा वह ॥ ३ ॥

द्विषते । तत् । परा । वह । शपते । तत् । परा । वह ॥ ३ ॥

यं द्विष्मो यच्च नो द्वेष्टि तस्मा एनद् गमयामः ॥ ४ ॥

यम् । द्विष्मः । यत् । च । नः । द्वेष्टि । तस्मै । एनत् । गमयामः ॥ ४ ॥

उषा देवी वाचा संविदाना वाग् देव्युषसा संविदाना ॥ ५ ॥

१ B $\overset{h}{B}$ E D R $\overset{m}{S}$ Dc दुःष्व°. We with A C K $\overset{m}{K}$ V. २ $\overset{h}{B}$ R $\overset{m}{S}$ Dc °दुःष्व°. ३ So we with all our authorities. See Rw. ४ $\overset{2}{P}$ एनम् ।. ५ D °व्यू१°. A B $\overset{h}{B}$ R Dc Cs °व्यु३°. C E K $\overset{m}{K}$ $\overset{m}{S}$ V °व्यू३°.

उषाः । देवी । वाचा । सम्ऽविदाना । वाक् । देवी । उषसा । सम्ऽविदाना ॥ ५ ॥

उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिरुषस्पतिना संविदानः ॥ ६ ॥

उषः । पतिः । वाचः । पतिना । सम्ऽविदानः । वाचः । पतिः । उषः । पतिना । सम्ऽविदानः ॥ ६ ॥

तेऽ[1]मुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥ ७ ॥

ते । अमुष्मै । परा । वहन्तु । अरायान् । दुःऽनाम्नः । सदान्वाः ॥ ७ ॥

कुम्भीका दूषीकाः पीयकान् ॥ ८ ॥

कुम्भीकाः । दूषीकाः । पीयकान् ॥ ८ ॥

जाग्रद्दुष्वप्न्यं[2] स्वप्नेदुष्वप्न्यम् ॥ ९ ॥

जाग्रत्ऽदुःस्वप्न्यम् । स्वप्नेऽदुःस्वप्न्यम् ॥ ९ ॥

अनागमिष्यतो वरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥ १० ॥

अनागमिष्यतः । वरान् । अवित्तेः । सम्ऽकल्पान् । अमुच्याः[3] । द्रुहः । पाशान् ॥ १० ॥

तदमुष्मा अग्ने देवाः परा वहन्तु वध्रिर्यथासद् विथुरो[4] न साधुः ॥ ११ ॥

तत् । अमुष्मै । अग्ने । देवाः । परा । वहन्तु । वध्रिः । यथा । असत् । विथुरः । न । साधुः ॥ ११ ॥

इति द्वितीयेनुवाके द्वितीयं पर्यायसूक्तम् ॥

तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥ १ ॥

तेन । एनम् । विध्यामि । अभूत्या । एनम् । विध्यामि । निःऽभूत्या । एनम् । विध्यामि । पराऽभूत्या । एनम् । विध्यामि । ग्राह्या । एनम् । विध्यामि । तमसा । एनम् । विध्यामि ॥ १ ॥

देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥ २ ॥

देवानाम् । एनम् । घोरैः । क्रूरैः । प्रऽएषैः । अभिऽप्रेष्यामि ॥ २ ॥

---

१ B^h V १ for ३. २ B E R Dc °द्वुःष्व°. We with A B^h C D K K^m S^m V Cs P P^2 J Cp. ३ P °चाः।. ४ Rw read °संद्विथुरो. All our authorities have °सद्विथुरो. Rw's MSS. also have the same accent here as our authorities (*vide* Whitney's *Index*).

वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥ ३ ॥

वैश्वानरस्य । एनम् । दंष्ट्रयोः । अपि । दधामि ॥ ३ ॥

एवानेवाव सा गरत् ॥ ४ ॥

एव । अनेव । अव । सा । गरत् ॥ ४ ॥

योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥ ५ ॥

यः । अस्मान् । द्वेष्टि । तम् । आत्मा । द्वेष्टु । यम् । वयम् । द्विष्मः । सः । आत्मानम् । द्वेष्टु ॥ ५ ॥

निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद् भजाम ॥ ६ ॥

निः । द्विषन्तम् । दिवः । निः । पृथिव्याः । निः । अन्तरिक्षात् । भजाम ॥ ६ ॥

सुयामंश्चाक्षुषे ॥ ७ ॥

सुऽयामन् । चाक्षुष ॥ ७ ॥

इदमहमामुष्यायणे३ऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥ ८ ॥

इदम् । अहम् । आमुष्यायणे । अमुष्याः । पुत्रे । दुःऽस्वप्न्यम् । मृजे ॥ ८ ॥

यददोअदो अभ्यगच्छन् यद् दोषा यत् पूर्वां रात्रिम् ॥ ९ ॥

यत् । अदःऽअदः । अभिऽअगच्छन् । यत् । दोषा । यत् । पूर्वाम् । रात्रिम् ॥ ९ ॥

यज्जाग्रद् यत् सुप्तो यद् दिवा यन्नक्तम् ॥ १० ॥

यत् । जाग्रत् । यत् । सुप्तः । यत् । दिवा । यत् । नक्तम् ॥ १० ॥

यदहरहरभिगच्छामि तस्मादेनमव दये ॥ ११ ॥

यत् । अहःऽअहः । अभिऽगच्छामि । तस्मात् । एनम् । अव । दये ॥ ११ ॥

तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥ १२ ॥

तम् । जहि । तेन । मन्दस्व । तस्य । पृष्टीः । अपि । शृणीहि ॥ १२ ॥

---

१ **C V** यो१°. २ **B^h S^m** °चाक्षुषः. ३ **P** °यामम् ।. We with **P^2 J C**p. ४ **B C E K^m R D**c **C**s दुःष्व°. We with **A B^h D K S^m V.** ५ All our authorities have °च्छन् distinctly. **R**w's MSS. too have, it appears from the *Index*, the same reading. The emendation to °च्छम् made by **R**w does not appear to be quite necessary, though at first sight desirable. ६ **B B^h E** यद्दिवा. ७ **R S^m C**s दयेत्. ८ **C K K^m V C**s **P J C**p °ष्टी°. We with **A B^h D E R S^m D**c **P^2**.

स मा जीवीत् तं प्राणो जहातु ॥ १३ ॥

सः। मा। जीवीत्। तम्। प्राणः। जहातु ॥ १३ ॥

इति द्वितीयेऽनुवाके तृतीयं पर्यायसूक्तम् ॥

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥ १ ॥

जितम्। अस्माकम्। उत्ऽभिन्नम्। अस्माकम्। ऋतम्। अस्माकम्। तेजः। अस्माकम्। ब्रह्म। अस्माकम्। स्वः। अस्माकम्। यज्ञः। अस्माकम्। पशवः। अस्माकम्। प्रऽजाः। अस्माकम्। वीराः। अस्माकम् ॥ १ ॥

तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥ २ ॥

तस्मात्। अमुम्। निः। भजामः। अमुम्। आमुष्यायणम्। अमुष्याः। पुत्रम्। असौ। यः ॥ २ ॥

स ग्राह्याः पाशान्मा मोचि ॥ ३ ॥

सः। ग्राह्याः। पाशात्। मा। मोचि ॥ ३ ॥

तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥ ४ ॥

तस्य। इदम्। वर्चः। तेजः। प्राणम्। आयुः। नि। वेष्टयामि। इदम्। एनम्। अधराञ्चम्। पादयामि ॥ ४ ॥

जितम् ०।०। स निर्ऋत्याः पाशान्मा मोचि। ० ॥ ५ ॥

०। सः। निःऽऋत्याः। पाशात्।० ॥ ५ ॥

जितम् ०।०। सोऽभूत्याः पाशान्मा मोचि। ० ॥ ६ ॥

०। सः। अभूत्याः। पाशात्।० ॥ ६ ॥

जितम् ०।०। स निर्भूत्याः पाशान्मा मोचि। ० ॥ ७ ॥

०। सः। निःऽभूत्याः। पाशात्।० ॥ ७ ॥

जितम् ०।०। स पराभूत्याः पाशान्मा मोचि। ० ॥ ८ ॥

०। सः। पराऽभूत्याः। पाशात्।० ॥ ८ ॥

---

१ P मा। We with P[2] J Cp.

जितम् ०।० । स दे॑वजामीनां पाशान्मा मो॑चि । ० ॥ ९ ॥

०। सः । देवऽजामीनाम् । पाशा॑त् ।० ॥ ९ ॥

जितम् ०।० । स बृहस्पतेः पाशान्मा मो॑चि । ० ॥ १० ॥

०। सः । बृहस्पते॑ः । पाशा॑त् ।० ॥ १० ॥

जितम् ०।० । स प्रजाप॑तेः पाशान्मा मो॑चि । ० ॥ ११ ॥

०। सः । प्रजाऽप॑तेः । पाशा॑त् ।० ॥ ११ ॥

जितम् ०।० । स ऋ॒षी॑णां पाशान्मा मो॑चि । ० ॥ १२ ॥

०। सः । ऋ॒षी॑णाम् । पाशा॑त् ।० ॥ १२ ॥

जितम् ०।० । स आ॑र्षे॑याणां पाशान्मा मो॑चि । ० ॥ १३ ॥

०। सः । आर्षे॑याणा॑म् । पाशा॑त् ।० ॥ १३ ॥

जितम् ०।० । सोऽङ्गि॑रसां पाशान्मा मो॑चि । ० ॥ १४ ॥

०। सः । अङ्गि॑रसाम् । पाशा॑त् ।० ॥ १४ ॥

जितम् ०।० । स आ॑ङ्गिरसानां पाशान्मा मो॑चि ।० ॥ १५ ॥

०। सः । आङ्गिरसाना॑म् । पाशा॑त् ।० ॥ १५ ॥

जितम् ०।० । सोऽथ॑र्वणां पाशान्मा मो॑चि । ० ॥ १६ ॥

०। सः । अथ॑र्वणाम् । पाशा॑त् ।० ॥ १६ ॥

जितम् ०।० । स आ॑थर्वणानां पाशान्मा मो॑चि । ० ॥ १७ ॥

०। सः । आथर्वणाना॑म् । पाशा॑त् ।० ॥ १७ ॥

जितम् ०।० । स वनस्पती॑नां पाशान्मा मो॑चि । ० ॥ १८ ॥

०। सः । वनस्पती॑नाम् । पाशा॑त् ।० ॥ १८ ॥

जितम् ०।० । स वा॑नस्पत्यानां पाशान्मा मो॑चि । ० ॥ १९ ॥

०। सः । वानस्पत्याना॑म् । पाशा॑त् ।० ॥ १९ ॥

जितम् ०।० । स ऋ॒तूनां पाशान्मा मो॑चि । ० ॥ २० ॥

०। सः । ऋतूनाम् । पाशा॑त् ।० ॥ २० ॥

---

१ A B B̊ C D E K K̊ R S̊ P J ऋ॒षी॑णां. Rw's MSS. had the same accent. Dc स ऋ॒षी॑णां changed to सर्षी॑णां. We with Cs P̊ V.

जितम् ०।० । स आर्तवानां पाशान्मा मोचि । ० ॥ २१ ॥

०। सः । आर्तवानाम् । पाशात् ।० ॥ २१ ॥

जितम् ०।० । स मासानां पाशान्मा मोचि । ० ॥ २२ ॥

०। सः । मासानाम् । पाशात् ।० ॥ २२ ॥

जितम् ०।० । सोऽर्धमासानां पाशान्मा मोचि । ० ॥ २३ ॥

०। सः । अर्धऽमासानाम् । पाशात् ।० ॥ २३ ॥

जितम् ०।० । सोऽहोरात्रयोः पाशान्मा मोचि । ० ॥ २४ ॥

०। सः । अहोरात्रयोः । पाशात् ।० ॥ २४ ॥

जितम् ०।० । सोऽह्नोः संयतोः पाशान्मा मोचि । ० ॥ २५ ॥

०। सः । अह्नोः । सम्ऽयतोः । पाशात् ।० ॥ २५ ॥

जितम् ०।० । स द्यावापृथिव्योः पाशान्मा मोचि । ० ॥ २६ ॥

०। सः । द्यावापृथिव्योः । पाशात् ।० ॥ २६ ॥

जितम् ०।० । स इन्द्राग्न्योः पाशान्मा मोचि । ० ॥ २७ ॥

०। सः । इन्द्राग्न्योः । पाशात् ।० ॥ २७ ॥

जितम् ०।० । स मित्रावरुणयोः पाशान्मा मोचि । ० ॥ २८ ॥

०। सः । मित्रावरुणयोः । पाशात् ।० ॥ २८ ॥

जितम् ०।० । स राज्ञो वरुणस्य पाशान्मा मोचि । ० ॥ २९ ॥

०। सः । राज्ञः । वरुणस्य । पाशात् ।० ॥ २९ ॥

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं
यज्ञोऽस्माकं पशवोस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥ ३० ॥

०। अस्माकम् । ऋतम् । अस्माकम् । तेजः । अस्माकम् । ब्रह्म । अस्माकम् । स्वः । अस्माकम् । यज्ञः । अस्माकम् । पशवः । अस्माकम् । प्रऽजाः । अस्माकम् । वीराः । अस्माकम् ॥ ३० ॥

तस्मादमुं निर्भजामोमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥ ३१ ॥

तस्मात् । अमुम् । निः । भजामः । अमुम् । आमुष्यायणम् । अमुष्याः । पुत्रम् । असौ । यः ॥ ३१ ॥

स मृत्योः पड्वीशात् पाशान्मा मोचि ॥ ३२ ॥

सः । मृत्योः । पड्वीशात् । पाशात् । मा । मोचि ॥ ३२ ॥

तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥ ३३ ॥

तस्य । इदम् । वर्चः । तेजः । प्राणम् । आयुः । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥ ३३ ॥

इति द्वितीयेनुवाके चतुर्थं पर्यायसूक्तम् ॥

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥ १ ॥

जितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वाः । पृतनाः । अरातीः ॥ १ ॥

तदग्निराह तदु सोम आह पूषा मा धात् सुकृतस्य लोके ॥ २ ॥

तत् । अग्निः । आह । तत् । ऊं इति । सोमः । आह । पूषा । मा । धात् । सुऽकृतस्य । लोके ॥ २ ॥

अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥ ३ ॥

अगन्म । स्वः । स्वः । अगन्म । सम् । सूर्यस्य । ज्योतिषा । अगन्म ॥ ३ ॥

वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासं वसु मयि धेहि ॥ ४ ॥

वस्यःऽभूयाय । वसुऽमान् । यज्ञः । वसु । वंशिषीय । वसुऽमान् । भूयासम् । वसु । मयि । धेहि ॥ ४ ॥

द्वितीयेनुवाके पञ्चमं पर्यायसूक्तम् ॥

द्वितीयोनुवाकः ॥

इति षोडशं काण्डं समाप्तम् ॥

---

१ C पड्वी°. V Dc पड्बि°. २ A B B[h] R E Dc ३ for १. We with C D K K[m] S[m] V Cs.

The Second Paryâya of the Second Anuvâka of the Eleventh Kâṇḍa divided into Seventy two Avasânas according to the instructions contained in the Sarvânukramaṇikâ quoted in the Critical Notice (See Vol. I. page 20).

ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ १ ॥

ततः । च । एनम् । अन्येन । शीर्ष्णा । प्रऽआशीः । येन । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ १ ॥

ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ॥ २ ॥

ज्येष्ठतः । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ २ ॥

तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ३ ॥

तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ३ ॥

बृहस्पतिना शीर्ष्णा ॥ ४ ॥

बृहस्पतिना । शीर्ष्णा ॥ ४ ॥

तेनैनं प्राशिषं तेनैनमजीगमम् ॥ ५ ॥

तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ ५ ॥

एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ॥ ६ ॥

एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ ६ ॥

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ७ ॥

सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः । एवम् । वेद ॥ ७ ॥

ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥ ८ ॥

°एनम् । अन्याभ्याम् । श्रोत्राभ्याम् । प्रऽआशीः । याभ्याम् । च ।० ॥ ८ ॥

बधिरो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न
प्रत्यञ्चम् ॥ ९ ॥

बधिरः । भविष्यसि । इति ।०० ॥ ९ ॥

द्यावापृथिवीभ्यां श्रोत्राभ्याम् ॥ १० ॥

द्यावापृथिवीभ्याम् । श्रोत्राभ्याम् ॥ १० ॥

ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः
सर्वपरुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ११ ॥

ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् ।००० ॥ ११ ॥

ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥ १२ ॥

°एनम् । अन्याभ्याम् । अक्षीभ्याम् । प्रऽआशीः । याभ्याम् । च ।० ॥ १२ ॥

अन्धो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् १३

अन्धः । भविष्यसि । इति ।०० ॥ १३ ॥

सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ॥ १४ ॥

सूर्याचन्द्रमसाभ्याम् । अक्षीभ्याम् ॥ १४ ॥

ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः
सर्वपरुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १५ ॥

ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् ।००० ॥ १५ ॥

ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ १६ ॥

°एनम् । अन्येन । मुखेन । प्रऽआशीः । येन । च ।० ॥ १६ ॥

मुखतस्ते प्रजा मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न
प्रत्यञ्चम् ॥ १७ ॥

मुखतः । ते । प्रऽजा । मरिष्यति । इति ।०० ॥ १७ ॥

ब्रह्मणा मुखेन ॥ १८ ॥

ब्रह्मणा । मुखेन ॥ १८ ॥

तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्व-
परुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ १९ ॥

तेन॑ । एनम् । प्र । आशिषम् । तेन॑ । एनम् ।००० ॥ १९ ॥

ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ॥ २० ॥

°एनम् । अन्यया॑ । जिह्वया॑ । प्रऽआशीः । यया॑ । च ।० ॥ २० ॥

जिह्वा ते मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् २१

जिह्वा । ते । मरिष्यति । इति॑ ।०० ॥ २१ ॥

अग्नेर्जिह्वया ॥ २२ ॥

अग्नेः । जिह्वया॑ ॥ २२ ॥

तयैनं प्राशिषं तयैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ २३ ॥

तया॑ । एनम् । प्र । आशिषम् । तया॑ । एनम् ।००० ॥ २३ ॥

ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ॥ २४ ॥

°एनम् । अन्यैः । दन्तैः । प्रऽआशीः । यैः । च ।० ॥ २४ ॥

दन्तास्ते शत्स्यन्तीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ २५ ॥

दन्ताः । ते । शत्स्यन्ति । इति॑ ।०० ॥ २५ ॥

ऋतुभिर्दन्तैः ॥ २६ ॥

ऋतुऽभिः । दन्तैः ॥ २६ ॥

तैरेनं प्राशिषं तैरेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ २७ ॥

तैः । एनम् । प्र । आशिषम् । तैः । एनम् ।००० ॥ २७ ॥

ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ॥ २८ ॥

°एनम् । अन्यैः । प्राणापानैः । प्रऽआशीः । यैः । च ।० ॥ २८ ॥

प्रणापानास्त्वा हास्यन्तीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ २९ ॥

प्राणापानाः । त्वा । हास्यन्ति । इति॑ ।०० ॥ २९ ॥

सप्तर्षिभिः प्राणापानैः ॥ ३० ॥

सप्तर्षिऽभिः । प्राणापानैः ॥ ३० ॥

तैरेनं प्राशिषं तैरेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद॥३१॥

तैः । एनम् । प्र । आशिषम् । तैः । एनम् ।०००॥ ३१ ॥

ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ ३२ ॥

°एनम् । अन्येन । व्यचसा । प्रऽआशीः । येन । च ।०॥ ३२ ॥

राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ३३ ॥

राजऽयक्ष्मः । त्वा । हनिष्यति । इति ।००॥ ३३ ॥

अन्तरिक्षेण व्यचसा ॥ ३४ ॥

अन्तरिक्षेण । व्यचसा ॥ ३४ ॥

तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद॥३५॥

तेन । एनम् । प्र । आशिषम् । तेन । एनम् ।०००॥ ३५ ॥

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ ३६ ॥

°अन्येन । पृष्ठेन । प्रऽआशीः ।०॥ ३६ ॥

विद्युत् त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ३७ ॥

विऽद्युत् । त्वा । हनिष्यति । इति ।००॥ ३७ ॥

दिवा पृष्ठेन । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ३८ ॥

दिवा । पृष्ठेन ।०००॥ ३८ ॥

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ ३९ ॥

°अन्येन । उरसा । प्रऽआशीः ।०॥ ३९ ॥

कृष्या न रात्स्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ४० ॥

कृष्या । न । रात्स्यसि । इति ।०० ॥ ४० ॥

पृथिव्योरसा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ४१

पृथिव्या । उरसा ।००० ॥ ४१ ॥

ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ ४२ ॥

°अन्येन । उदरेण । प्रऽआशीः ।० ॥ ४२ ॥

उदरदारस्त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ४३ ॥

उदरऽदारः । त्वा । हनिष्यति । इति ।०० ॥ ४३ ॥

सत्येनोदरेण । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ४४ ॥

सत्येन । उदरेण ।००० ॥ ४४ ॥

ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ॥ ४५ ॥

°एनम् । अन्येन । वस्तिना । प्रऽआशीः । येन । च ।० ॥ ४५ ॥

अप्सु मरिष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ४६

अप्ऽसु । मरिष्यसि । इति ।०० ॥ ४६ ॥

समुद्रेण वस्तिना ॥ ४७ ॥

समुद्रेण । वस्तिना ॥ ४७ ॥

तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ४८ ॥

तेन । एनम् । प्र । आशिषम् । तेन । एनम् ।००० ॥ ४८ ॥

ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥ ४९ ॥

°एनम् । अन्याभ्याम् । ऊरुऽभ्याम् । प्रऽआशीः । याभ्याम् । च ।० ॥ ४९ ॥

ऊरू ते मरिष्यत इत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ५०

ऊरू इति । ते । मरिष्यतः । इति ।०० ॥ ५० ॥

मित्रावरुणयोरूरुभ्याम् ॥ ५१ ॥

मित्रावरुणयोः । ऊरुऽभ्याम् ॥ ५१ ॥

ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ५२ ॥

ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् ।००० ॥ ५२ ॥

ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥ ५३ ॥

°अन्याभ्याम् । अष्ठीवत्ऽभ्याम् । प्रऽआशीः ।० ॥ ५३ ॥

स्रामो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ५४ ॥

स्रामः । भविष्यसि । इति ।०० ॥ ५४ ॥

त्वष्टुरष्ठीवद्भ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ५५ ॥

त्वष्टुः । अष्ठीवत्ऽभ्याम् ।००० ॥ ५५ ॥

ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥ ५६ ॥

°अन्याभ्याम् । पादाभ्याम् । प्रऽआशीः ।० ॥ ५६ ॥

बहुचारी भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ५७ ॥

बहुऽचारी । भविष्यसि । इति ।०० ॥ ५७ ॥

अश्विनोः पादाभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।

एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ५८ ॥

अश्विनोः । पादाभ्याम् ।००० ॥ ५८ ॥

ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥५९॥

°अन्याभ्याम् । प्रऽपदाभ्याम् । प्रऽआशीः ।० ॥ ५९ ॥

सर्पस्त्वा हनिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ६० ॥

सर्पः । त्वा । हनिष्यति । इति ।०० ॥ ६० ॥

सवितुः प्रपदाभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ६१ ॥

सवितुः । प्रऽपदाभ्याम् ।००० ॥ ६१ ॥

ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ॥६२॥

°एनम् । अन्याभ्याम् । हस्ताभ्याम् । प्रऽआशीः । याभ्याम् । च ।० ॥ ६२ ॥

ब्राह्मणं हनिष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ६३ ॥

ब्राह्मणम् । हनिष्यसि । इति ।०० ॥ ६३ ॥

ऋतस्य हस्ताभ्याम् ॥ ६४ ॥

ऋतस्य । हस्ताभ्याम् ॥ ६४ ॥

ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ६५ ॥

ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् ।००० ॥ ६५ ॥

ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ॥ ६६ ॥

ततः । च । एनम् । अन्यया । प्रतिऽस्थया । प्रऽआशीः । यया । च । एतम् । पूर्वे । ऋषयः । प्रऽआश्नन् ॥ ६६ ॥

अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ॥ ६७ ॥

अप्रतिऽस्थानः । अनायतनः । मरिष्यसि । इति । एनम् । आह ॥ ६७ ॥

तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ॥ ६८ ॥

तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ६८ ॥

सत्ये प्रतिष्ठाय ॥ ६९ ॥

सत्ये । प्रतिऽस्थाय ॥ ६९ ॥

तयैनं प्राशिषं तयैनमजीगमम् ॥ ७० ॥

तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ ७० ॥

एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ॥ ७१ ॥

एषः । वै । ओदनः । सर्वऽअङ्गः । सर्वऽपरुः । सर्वऽतनूः ॥ ७१ ॥

सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥ ७२ ॥

सर्वऽअङ्गः । एव । सर्वऽपरुः । सर्वऽतनूः । सम् । भवति । यः ।० ॥ ७२ ॥

CORRECTIONS. Vol. III.

पृष्ठे	पङ्क्तौ	अशुद्धम्.	शुद्धम्.
३	९	शीलिकमि०	शीलिकामि०
,,	२७	Omit “1. S′ शीलिका०”	
२७	२५	B निर्ऋ॑तेभा०	B निर्ऋँ॑तेभा०
३५	२२	अन्यासा	अन्यासां
५०	१	प्रजाया	प्रजायां
,,	२	°हिंसकाना	°हिंसकानां
५८	१७	कणादीना	कणादीनां
६२	८	°भीन्ध्रे॑ ।	°भी॒न्ध्रे॑ ।
६९	१	°ताभ्या	°ताभ्यां
,,	७	°म॒क्षीभ्या॒	°म॒क्षीभ्यां॒
७९	८	ए॒वम् वेदं॑ ।	ए॒वम् । वेदं॑ ।
९२	१३	कच्छ्र०	कृच्छ्र०
१०६	६	सम्ऽगृभ्य॑ ।	स॒म्ऽगृभ्य॑ ।
१०९	२४	ता	तां
११८	१	उदर॑म् ।	उ॒दर॑म् ।
१४२	१	गुहाया	गुहायां
१५९	७	वर्णोपजन०	वर्णोपजन० (अच्छब्दलोप० ?)
१६५	२३	ःवास्तेयी०	वास्तेयी०
१६६	३	आसनस्य	आसनस्य (आस्नस्य ?)
१७७	१३	पक्षिश्व०	पक्षिश्व० (पक्षिणःश्व० ?)
१८०	६	°राक्षसाश्च	°राक्षसांश्च
१९७	८	तासा	तासां
२१८	२३	सीसे	सीसे॒
२२४		°संहिताया	°संहितायां
,,	२६	KJ पि॒ष्टा.	K पि॒ष्टा.
२३३	६	प॒रः॒ऽप॑रः ।	प॒रःऽप॑रः ।
२३४	२६	$\overset{m}{\text{K}}$ S	K $\overset{m}{\text{S}}$

पृष्ठे	पङ्क्तौ	अशुद्धम्.	शुद्धम्.
२५८		°संहिताया	°संहितायां
२६६	२०	परि॒ शुम्भ॑ति॒	परि॒शुम्भ॑ति॒
२७१	१०	सि॒षा॒स॒ति॒ ।	सि॒सा॒स॒ति॒ ।
२७२	८	दे॒वाना॒	दे॒वानां॒
२८६		°संहिताया	°संहितायां
३०४		,,	,,
३२१	२५	य एव	य एवं
३२२	१६	॥ १८ ॥	॥ १९ ॥
३३८	१९	दे॒वता॒	दे॒वतां॒
३४२	१४	अ॒स्य॒ ।	०। अ॒स्य॒ ।
३४३	८	स॒प्तमः ।	०। स॒प्तमः ।
३४४	९	एक॑म् ।	०। एक॑म् ।
३४८		°संहिताया	संहितायां

INDEX.

अ.

अंश॑ः **६**. ४, २; **२०**. ५९, ३.
अंश॑म् **७**. ५२, ४; **११**. ८, २.
अं॒शव॑ः **९**. ६, १४; **११**. १, १८; **१९**. ६, १६; **२०**. १४२, ४.
अंशा॑न् **११**. १, ५.
अं॒शुः **५**. २९, १३.
अं॒शुःऽइ॑व **५**. २९, १२.
अं॒शुम् **७**. ८६, ६; **२०**. ८७, १.
अं॒शु॒ऽमती॑ः **८**. ७, ४.
अं॒शु॒ऽमती॑म् **२०**. १३७, ७.
अं॒शु॒ऽमत्या॑ः **२०**. १३७, ८; ९.
अं॒शु॒ऽमन्त॑म् **१३**. २, ७.
अं॒शु॒ऽमान् **८**. १, २.
अं॒शून् **६**. ४९, २; **११**. १, ९; **१२**. ३, २०.
अं॒शून्ऽइ॑व **५**. २०, १०.
अं॒शो॒ इति॑ **७**. ८६, ३.
अं॒स॒द्रीम् **११**. १, २३.
अंसा॑भ्याम् **२**. ३३, २; **२०**. ९६, १८.
अंसे॑ **८**. ६, १३.
अंसौ॑ **९**. ४, ८; १२, ७; **१०**. २, ५; ९, १९; **११**. ३, ९.
अं॒ह॒ःऽमुच॑म् **१९**. ४२, ४.
अं॒ह॒ःऽमुचे॑ **१९**. ४२, ३.
अंह॑सः **२**. ४, ३; २८, १; **४**. १०, १; ३; २३, १; २; ३; ४; ५; ६; ७; २४, १; २; ३; ४; ५; ६; ७; २५, १; २; ३; ४; ५; ६; ७; २६, १; २; ३; ४; ५; ६; ७; २७, १; २; ३; ४; ५; ६; ७; २८, १; २; ३; ४; ५; ६; ७; २९, १; २; ३; ४; ५; ६; ७; **६**. ३, २; ४५, ३; ९६, १; **७**. ६६, १; ११७, १; **८**. २, १८; ४, २३; ७, १३; **१०**. ५, २२; **११**. ८, १; २; ३; ४; ५; ६; ८; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; **१४**. २, ४५; **१९**. ४४, ८; ९.
अंह॑सःऽअंहसः **१**. ३१, २.
अंह॑ऽसु **६**. ३५, २.
अंहां॑सि **२०**. १२, २.
अं॒हु॒रः **५**. १, ६.
अं॒हु॒र॒णा **९**. २, ३.
अं॒हु॒र॒णात् **६**. ९९, १.
अक॑ः **१**. ८, १.
अ॒क॒ः **२**. २५, १; **७**. ३१, १; **१०**. ६, १९; ३०; **११**. ६, ६; **२०**. ९१, ४.
अक॑रः **१२**. ३, ३८.
अ॒क॒र॒ः **६**. १२८, ४; **१३**. १, २०.
अ॒क॒र॒त् **१**. २४, २; **९**. २, ११.
अक॑रम् **६**. ११५, २.
अ॒क॒र॒म् **१**. ३२, ४; **२**. २, ५; **५**. ७, ९; १०; २३, ८; २८, ७; **६**. १०४, २; १३८, ३[३]; **८**. २, ४; **११**. २, १६; ३०; **१२**. १, २६; **१४**. २, ४६.
अक॒रित्यक॑ः **२०**. ३४, ४.

अकरोत् १०. २, १६.
अकर्ताम् ६. १४१, २.
अकर्म १८. ३, २४.
अकर्म ७. १०२, ४; २०. १६, १२.
अकल्पत १३. १, ४६; ५३.
अकल्पन्त ११. ३, २१.
अकल्पयत् १०. २, १९^{२}; ६, २१; १३. १, ५३; १४. १, ५५.
अकल्पयथाः १२. १, ५५.
अकल्पयन् ९. ४, १४.
अकल्पयन् ६. १०९, १; १९. ६, ५; ८.
अकल्पयन्त १८. ४, ७.
अकवचः ११. १२, २२.
अकामः १०. ८, ४४.
अकामऽकर्शनः २०. २१, २.
अकामाः ६. ११४, ३.
अकारि २०. १९, ३.
अकारिषम् ७. ८, १; २०. १३७, ३.
अकुर्वत ६. १२८, १.
अकुर्वन् १५. ४, २; ५; ८; ११; १४; १७.
अकुर्वन् १५. ५, १; ४; ६; ८; १०; १२; १४.
अकूपारः ५. १७, १.
अकृणोः १४. १, ४१.
अकृणोः ७. ८९, २.
अकृणोत् १०. ७, ९; १९. ४, १; २०. १७, ८.
अकृणोत् ९. १५, ६; २०. ११, ३; १६, ६.
अकृण्वत २०. ९४, ६.
अकृण्वत ८. ५, १४.
अकृण्वन् १. २५, १; ४. २३, ६; ७. ८४, १; ११. १, २४.
अकृण्वन् १०. २, २.
अकृतम् २०. ९७, ३.
अकृत्तऽरुक् ४. ३१, ४.
अकृन्तत् २०. ९१, ५.
अकृन्तन् १४. १, ४५.
अकृपयत् २०. १६, १०.
अकृपेताम् २०. ४२, २.
अकृप्रन् १८. ३, २३.
अकृष्टऽपच्ये ५. २९, ७.
अकेतवे २०. २६, ६; ४७, १२; ६९, ११.
अक्तम् ७. १०३, १^{२}.
अक्तुऽभिः १३. २, १७; २२; १७. १, ९; १८. १, ५५; २०. ४७, १४; १९.
अक्तून् १८. १, ३९.
अक्रत २०. १३८, ३.
अक्रत ३. १०, ५; ५. ३, १०; ६. २८, २; ४९, ३.
अक्रतुः ४. ३२, ५.
अक्रतुम् ३. २५, ६.
अक्रन् २. २९, ७; ३. ४, ७; ४. २१, १; १८. १, ५५; ३, २२; २०. ३५, १६.
अक्रन्दयत् ८. ९, २.
अक्रमत ४. ११, ७^{३}; ९. ५, २०.
अक्रमन् ४. ३, १.
अक्रमीत् १. १७, ४; ३. ७, २; ६. ३१, १; ८. १, २१; १९. ३६, ५; २०. ४८, ४.
अक्रव्यऽअत् १२. २, ३; ४२.
अक्रामत् ८. १०, २^{२}; ४^{२}; ६^{२}; ८^{२}; १०^{२}; १२^{२}; ११, १; १२, १; ३; ५; ७; १३, १; ५; ९; १३; १४, १; ५; ९; १३; १९. ६, २; १९, १; २; ३; ४; ५; ६; ७; ८; ९; ११.
अक्रामन् १९. १९, १०.

अक्रीणन् **४.** ७, ६.
अक्षः **९.** १४, ११; **१४.** १, १२; **१९.** ५३, २.
अक्षऽकामाः **२.** २, ५.
अक्षण्ऽवान् **९.** १४, १५.
अक्षतः **१२.** १, ११.
अक्षऽद्रुग्धः **५.** १८, २.
अक्षन् **१८.** ४, ६१.
अक्षन् **१८.** ३, ४२; ४, ६५.
अक्षऽपराजयम् **४.** १७, ७.
अक्षम् **२०.** १२२, २; ३.
अक्षये **१९.** ५२, ३.
अक्षरन् **२०.** १३७, ४.
अक्षराः **१३.** ३, ६.
अक्षरे **९.** १५, १८.
अक्षरेण **९.** १५, २; **१८.** ३, ४०.
अक्षऽवृत्तम् **६.** ११८, २.
अक्षाः **७.** ५२, ९.
अक्षाः **६.** ७०, १; **७.** ११४, ६; **१४.** १, ३६.
अक्षाणाम् **६.** ११८, १; **७.** ११४, ५.
अक्षात् **२.** १४, २.
अक्षान् **७.** ११४, ७.
अक्षान्ऽइव **४.** १६, ५.
अक्षि **१.** ८, ३; **१५.** १८, २^{२}.
अक्षिणी इति **१०.** ९, १४; **११.** ३, २.
अक्षितऽऊतयः **२०.** १०, १; ५९, १.
अक्षितऽऊतिः **२०.** ६९, ७.
अक्षितः **४.** ५, ७; **६.** १४२, २; **९.** १, ६; **११.** १, २०.
अक्षितम् **३.** २४, ४^{२}; ७; २९, ४; ५; **४.** २७, २; **७.** ८६, ६; **१८.** ४, ३६; **१९.** ५४, ४; **२०.** ७१, १३.
अक्षितस्य **७.** ८०, ४.
अक्षिता **२०.** ६, ७.
अक्षिताः **१.** १५, ३; **६.** १४२, ३^{४}; **७.** ८६, ६; **१०.** ६, १४.
अक्षिताम् **७.** १८, २; ८५, २; **१८.** ४, ३२.
अक्षितिः **११.** ९, २५; १०, ४; २६.
अक्षितिम् **१८.** ४, २७.
अक्षितौ **९.** १, ७.
अक्षीणि **४.** ५, ५.
अक्षीभ्याम् **२.** ३३, १; **११.** ४, ३^{२}; **२०.** ९६, १७.
अक्षीयमाणम् **७.** २१, ३.
अक्षुऽजालाभ्याम् **८.** ८, १८.
अक्षुध्याः **७.** ६२, ४; ६.
अक्षुम् **९.** ३, ८.
अक्षेभ्यः **७.** ११४, २.
अक्षेषु **४.** ३८, ४; **५.** ३१, ६; **६.** ३८, ३; **७.** ११४, १; **१२.** ३, ५२; **१४.** १, ३५.
अक्षैः **७.** ५२, १.
अक्षौ **१९.** ५०, १.
अक्ष्णुहि **४.** २२, १.
अक्ष्णोः **१९.** ६०, १.
अक्ष्यम् **४.** ९, १.
अक्ष्योः **५.** ४, १०; **६.** २४, २; १२७, ३.
अक्ष्यौ **१.** २७, १; **४.** ३, ३; **५.** २३, ३; २९, ४; **६.** ९, १^{२}; **७.** ३७, १.
अक्ष्व **१९.** ४५, ९.
अखनत् **४.** ४, १; **६.** १३७, १; **७.** २५, १.
अखनत् **२.** २७, २; **५.** १४, १.
अखनन् **६.** १०९, ३.
अखर्वम् **२०.** ५९, ४.
अखातम् **५.** १३, १.
अख्यत् **१८.** १, २४.

अ॒ख्य॒त् **६.** ३१, २; **७.** ७७, ६; ८७, ४; ५; **१०.** १०, १५; **१३.** २, ९; **१८.** १, २७; २८; ३, २३; **२०.** ४८, ५.

अग॑च्छः **२०.** ६२, ७.

अ॒ग॒च्छ॒त् **८.** १२, १; ३; ५; ७; १३, १; ५; ९; १३; १४, १; ५; ९; १३; **१५.** ७, १.

अ॒ग॒च्छ॒न्त॒ **७.** ८४, २; **१०.** १०, १७.

अग॑त **१०.** १०, १३; १४; १५.

अग॑तस्य **११.** १२, १६; **१४.** २, ७४.

अ॒ग॒दः **४.** १७, ८; **५.** २९, ६; ७; ८; ९.

अ॒ग॒दम् **५.** ४, ६; **६.** ९५, ३; **१८.** ३, ५५.

अग॑न् **१४.** २, ३६; ७४; **२०.** २०, ३; ५७, ६.

अ॒ग॒न् **२.** ९, ३; २९, ४; ३०, ५; **३.** ५, १; ४; १०, ८; **४.** ३७, ६; **५.** २६, ६; **६.** ६८, १; **७.** २६, १; २; ८४, ३[२]; **९.** ४, २२; **१०.** ४, १५; **११.** १, १४; **१२.** ३, १५; **१३.** २, ९; **१४.** २, ५; १३; १४; **१८.** १, ८; २, ५७; ४, ५०; ५३; **१९.** ३१, ७; ३७, १; ५२, ४; **२०.** ७६, ४; १२६, २२.

अग॑न्म **७.** ३३, १; ५५, ७; **१४.** २, ३६; **१६.** ९, ३; **१८.** ३, ६४.

अ॒ग॒न्म॒ **१६.** ९, ३[२]; **१९.** ५९, ३.

अग॑न्महि **६.** ५३, ३.

अ॒ग॒म॒त् **१.** ८, २; **६.** ३५, २; **१०.** ६, २; २२; २३; २४; २५; २६; २७; २८.

अग॑मन् **१४.** २, ७३.

अ॒ग॒म॒म् **२.** ३०, ५[२]; **४.** १३, ५; **६.** १२, १; **७.** ९४, १; **८.** ९, २२; **९.** १, १४; **१०.** ५, ४६; **१९.** ३५, ३.

अ॒गर्स्ति॑तम् **४.** २९, ३.

अ॒गस्त्य॑ः **४.** ३७, १; **१८.** ३, १५.

अ॒गस्त्य॑स्य **२.** ३२, ३; **५.** २३, १०.

अ॒गा॒ः **८.** १, २०; **१४.** २, १९; **१९.** २७, ८; **२०.** ९६, १०.

अ॒गा॒त् **१.** २८, १; २९, ५; **२.** ९, २[३]; ३; **५.** २८, ९; **६.** ३७, १; **९.** १४, १७; **१०.** ४, २६; **१२.** २, ४३; **१३.** १, ४१; २, ३५; **१४.** १, १३; **१७.** १, २४; **२०.** १०७, १४.

अ॒गा॒ता॒म् **२.** ८, १; **६.** १२१, ३.

अ॒गा॒म् **१.** ३४, ५; **४.** १४, ३; **१८.** २, ४५; **१९.** १४, १.

अगा॑म **३.** १५, ४.

अ॒गा॒म॒ **१२.** २, २२.

अ॒गा॒य॒त् **२०.** ९१, ३.

अ॒गु॒ः **२.** ५, २; **३.** १२, ७; **४.** २४, १; **८.** ९, १३[२]; **१०.** ३, ९; **११.** १, १०; १४; **१३.** १, १०; १४; **१९.** ५७, २[३]; **२०.** २४, ३.

अ॒गृ॒ह्न॒न् **१८.** २, ३३.

अ॒गृ॒भ्ण॒न् **१२.** ३, १६.

अ॒गृ॒भ्णा॒त् **१०.** १०, २५.

अ॒गोता॑म् **४.** १७, ६.

अगो॑ऽरुधाय **२०.** ६५, २.

अगो॑ह्यः **२०.** ६४, १.

अ॒ग्नय॑ः **२.** ३५, १; **३.** २१, १; **७.** ६९, १; **८.** १, ११; **९.** ४, १८; **१०.** ५, २१; **१२.** १, १९; ३७; ३, ५०; **१३.** २, १८; **१६.** १, १; **१८.** ४, १२; १३; **१९.** ९, ११; १२; १६, २; २७, १५; **२०.** ४७, १५.

अग्नयै **४.** ३९, १[२]; **६.** १०, १; ३४, १; **७.** ९२, १; **९.** ३, १२; **११.** १०, ३१; **१२.** ३, ५५; ४, ३४[२]; **१४.** २, ४; **१८.** ४, ७१; **१९.** ४, १; ४३, १; ५५, ५; **२०.** १, ३.

अग्नायी **७.** ५१, २.

अग्नाविष्णू इति **७.** ३०, १; २.

अग्निऽआधेयम् **११.** ९, ८.

अग्निः **१.** ७, ४; ९, १; २; १६, १; २; २५, १; २८, १; ३३, १; **२.** १, ४; १०, २; १२, ८; २८, २; २९, १; ३४, ३[२]; **३.** १, १; २; ३; ६; २, १; २; ४, ३; ८, १; ३; ११, ४; १५, ६; २१, ९; १०; २६, १; २७, १; ३१, ६; **४.** ११, ७; १५, १०; ३६, १; ३९, २; ९; **५.** ३, ३; ८, ३; १२, १०; ११; १७, २; १८, ६; १४; २२, १; २३, १; २४, २; २५, ४; २६, १; २७, ३; ५; ११; २८, २; ५; ३०, ११; ३१, १२; **६.** ३, २; २७, २; ३४, २; ५; ३५, १; २; ३६, ३; ३९, ३; ४५, २; ४७, १; ५३, १; ५८, ३; ७१, १; २; ७३, १; ७६, १; ८६, २; ८८, २; ९४, ३; ९७, १; १०६, ३; १११, २; १२०, १; १२१, २; **७.** १८, ४; २१, १; २५, १; ३४, १; ५५, २; ३; ६; ६४, १; ६५, १; ६६, २; ७७, १; २; ८७, ४; ५; ११९, २; **८.** ३, १; २४; २६; ५, ५; १०; १८; ८, २३; ९, ६; **९.** २, १३; २०; २४; ३, २१; २२; ४, ३; ५, ६; ७; १२, १; १९; **१०.** ३, १४; ४, २६; ६, ६; ७, २; ४; १२; ८, ३९; ९, २६; १०, ७; **११.** १, २; ३३; २, ८; ९, १; १०, ८; ९; ११, २५; **१२.** १, १९[३]; २०; ५३; २, ४; ७; ११; १२; १५; १६; ३३; ३५; ३८; ४४; ५०; ५२; ३, २; २४; २५; ४३; ९, ३; १०, १५; ११, ११; **१३.** १, ११; १७; २०; २७; २८[२]; ४८; ५३[२]; २, ४६; ३, ५; १३; ४, ५; ७, ८; **१४.** १, ८; ४८; ४९; २, २; ३; ४; ५९; ६०; ६१; ६२; **१५.** ४, १५; ६, २; १०, ७; १४, १५; १५, ३; १८, ३; **१६.** १, ७; ८; ४, ४; ७; ९, २; **१७.** १, ३०; **१८.** १, २७; २८; ३९; २, २८; ५४; ३, ११; ५५; ६५; ४, ८; ९; १५; ६४; **१९.** ४, १; ६, ७; १०, ४; १७, १; २४, ८; ३१, २; ३३, १; ३७, १; ४३, १[२]; ४५, ६; ५५, ३; ४; ५९, २; ३; **२०.** २, २; ९२, ८; ९६, ९; ११; १२; १०२, १; २.

अग्निःऽइव **२.** २५, ४; **४.** ३१, २; **५.** १४, १३; १८, ४; २२, २; **६.** ३७, २.

अग्निऽजाः **१०.** ४, २३.

अग्निऽजिह्वाः **११.** ११, १९.

अग्नितपःऽभिः **२०.** १६, ६.

अग्निऽतप्तेभिः **८.** ४, ५.

अग्निऽतेजाः **१०.** ५, २५.

अग्निऽदग्धाः **१८.** २, ३५.

अग्निऽदूतः **२.** १२, ७; **१८.** २, १.

अग्निऽधानात् **१२.** ३, ३५.

अग्निऽधाने **६.** २७, ३.

अग्निना **३.** १२, ९; **४.** १४, २; २३, ५; ३९, २; **५.** २३, १३; **६.** ८५, ३; **८.** ८, १७; **९.** ३, २३; ५, ५; **११.** २, २६; **१३.** १, २९; **१९.** ३७, १; ४५, ६;

अग्निऽभिः **३.** २०, ५; **२०.** १०३, २.
अग्निऽभ्यः **३.** २१, १; २; ३; ४; ५; ६; ७.
अग्निम् **१.** ६, २; ३३, १; २; ३; **३.** १६, १; २०, ४; २१, ८^{२}; ३०, ६; **४.** २३, ३; ४; ७; ४०, १; **५.** १८, ५; ३०, १२; **६.** १८, १; २८, २; **७.** ५२, ३; ६५, १; ८७, २^{२}; ११५, २; **८.** २, ९; ८, २; **९.** ३, १४; १५, २८^{२}; **१०.** २, २०; २१; ७, ३३; ८, १७; **११.** ८, १; **१२.** १, ६; १९; २०; २, ८; ९; १०; ५४; **१३.** १, २५; ४०; ५२; ५७; **१४.** १, ३९; २, १८; २०; २३; २४; २५; **१५.** ४, १४; १०, ९; **१८.** १, २०; २१; ३, २२; ६०; ४, १४; ४०; **१९.** १८, १; २७, ७; **२०.** १६, ९; ३४, ३; ६७, ३; १०१, १; १०३, १^{३}; ३.
अग्निम्ऽअग्निम् **२०.** १०१, २.
अग्निमान्ऽइव **८.** ४, २.
अग्निम्ऽइव **७.** ४७, १; **८.** २, ४.
अग्निऽमूढानाम् **६.** ६७, २.
अग्निऽरूपाः **४.** ३१, १.
अग्निऽवासाः **१२.** १, २१.
आग्निऽशालम् **९.** ३, ७.
अग्निषु **१५.** १२, २.
अग्निऽस्तोमः **११.** ९, ७.
अग्निऽस्तोमम् **१०.** ९, ८.
अग्निऽस्तोमेन **९.** ९, २.
अग्निऽस्तोमैः **१२.** ३, ३३.
अग्निऽस्वात्ताः **१८.** ३, ४४.
अग्निऽहोत्रम् **११.** ९, ९.
अग्निहोत्रऽहुताम् **३.** २८, ६.
आग्निऽहोत्राः **६.** ९७, १.
अग्निऽहोत्रे **१०.** ३, २२; **१५.** १२, २.
अग्नी इति **११.** ७, ११; **१३.** १, ४६; ४७; ४९^{२}; ५०; ५१.
अग्नीन् **१२.** २, ४; **१६.** १, १३.
अग्नीषोमा **१.** ८, २; **१८.** २, ५३.
अग्नीषोमा **६.** ९३, ३.
अग्नीषोमाभ्याम् **१२.** ४, २६.
अग्नीषोमीयः **९.** ६, ६.
अग्नीषोमौ **३.** १३, ५; **८.** ९, १४.
अग्नीषोमौ **६.** ६१, ३.
अग्नीषोमौ **६.** ५४, २.
अग्ने **१.** ७, २; **२.** १६, ४; १९, १; २; ३; ४; ५; **३.** ३, १; १५, ५; २०, २; २२, ३; **४.** १४, ५; ३३, १; **५.** ३, २; ८, १; १४, ८; २७, १२; २९, १; ४; १३; **६.** ५, १; ६३, ४; १०८, ४; १३०, ४; **७.** ३५, १; ६३, २; ७७, १०; ११५, १; **८.** ३, ४; ७; २०; २३; **९.** २, ४; ९; **१०.** ६, ३५; **११.** १, १; ३; ६; १६; **१२.** २, ४२; **१३.** १, ३१; **१४.** २, १; **१८.** १, ३४; २, ३६; ३, ५; ४, ३०; **१९.** ३, २; ३; २७, ५; ६४, १; **२०.** १३, ३; १०१, ३; १०२, ३; १०३, २.
अग्ने **१.** ७, १; ३; ६; ७; ८, ४^{२}; ९, ३; ४; **२.** ६, १; २^{२}; ३^{३}; ४^{३}; ५; १३, १^{२}; २८, ५; ३६, १; ३; **३.** १५, ३; ४; ८; २०, १; ५; ३१, १; **४.** ४, ६; ३३, ४; **५.** ३, १; ६, १०; १२, ३; २५, ७; २८, ४; २९, २; ३; ५; १०; ११; १४; १५; ३०, १४; **६.** ५, ३; ३२, १; ४९, १; १०३, २; ३; १०४, २; ११०, १; १११, १; ११२, १; २; ११७, १; २; ११९, १;

१२२, ४; १२४, १; ७. ५५, १; ६३, १; ७४, १; ७७, ९; ८३, १; २; ८७, ३^{२}; ६^{२}; ८९, १; ९४, १; २; १०२, ३; १११, १; ११३, १^{२}; ११४, २; ८. ३, ३; ५; ६; ८; ९; १०; ११; १२; १३; १५; १७; १८; १९; २०; २१; २२; ४, १०; १४; ९. १, १४; १५; ५, १७; १९; १४, १३; १०. ५, ४६; ४७; ४८; ४९; ११. १, ४; ३६; १२. २, ३; ५; ६; १७; १८; ४५; ४६; १३. ३, २१; ३३; १४. २, ६९; १६. ६, ११; १८. १, २२; २४; २५; २६; २, ४; १०; ३४; ३, ६; २१; ४२; ४७; ४८; ५३; ४, ९; १०; ११; ८८; १९. ३, ४; ७, २; ८, ३; ११, ६; ५५, १; २; ६; ५९, १; ६४, ३; ४; २०. १३, ४.

अग्नेः ३. १, ५; २, ३; १९, ४; ४. १४, १; २३, १; ३३, ५; ३६, २; ५. २७, १; ५; ८; ९; २८, ६; ६. ७६, २; ४; ७. ७३, ४; ५; ८. १, ४; २, १३; २७; २८; ७, ८; १६; ९. १, १; ३; १०; २, ६; ५, ६; १३; १०. ५, ७; ११. १, २५; ४, ५; १०, ९; १२. १, २०; २, ४०; ३, ३४; १३. १, ३०; २, ३५; ७, ८; १५. ६, ३; १८. २, ५८; ४, ८; १९. २६, १; २७, ५; ४५, ३; २०. १०७, १४.

अग्नेःऽइव ६. २०, १; ७. ४७, १; ८. ७, १५.

अग्नौ ४. ३९, ९; ५. ३१, ९; ६. २९, १; ३८, १; १२२, ३; ७. ७६, १; ९२, १; ९. ५, ५; १०. १, १८; ४, २२; ११. १, २९; ७, १३; १२. २, १३; १९; ३, ७; ५४; १७. १, १३.

अग्मत २. ३०, २.

अग्मन् २०. ८९, ८.

अग्मन् ४. २१, १; २०. १४३, ६.

अग्रऽइत्वरी १२. १, ५७.

अग्रतः ४. १०, २; ५. १७, १४.

अग्रंभम् १०. ४, १९.

अग्रभम् ४. २०, ८; ५. १३, १; २; ३; ६. ८३, २; १९. ३८, २.

अग्रंभीत् १. १२, २.

अग्रभीत् ७. ११५, ३; ८. १, २; १७; १०. ९, २; १८. ३, १६.

अग्रंम् २. २६, २; ४. १, ५; १९, ३; ३२, ७; ६. १३७, ३; ७. १, १; ३, १; ८६, २; ८७, ४; ५; ८. ७, ३; १२; १०. ८, ८; १२. ३, १०; १४. १, २४; १६. १, ६; १८. १, २७; २८.

अग्रंवः १४. २, ७२.

अग्रवः १८. २, ४७.

अग्रऽशः १२. ४, ३३; १९. ६, ११.

अग्रंहीत् ५. १७, ८.

अग्रहीत् १४. १, ५१^{२}.

अग्रा ८. ३, १०.

अग्रियः ५. २, ८; २०. १०७, ११.

अग्रियम् ११. ८, ३.

अग्रुवै ६. ६०, १; ३.

अग्रे १. ३४, २; २. २९, ७; ३४, ३; ४; ३. ४, ४; ९, ६; १२, ५; २२, ३; ४. १, २; २, ६; ७; ८; १४, १^{२}; १९, ४; २८, ४; ५. १२, ४; २८, ११; ६. ११६, १; ७. ८७, २; ११५, २; ८. १०, १; ९. ४, २; ५, २०; १४, ८; २१; १०. ७, २८; ८, २१^{२}; ११. १, २३; १२, १५; १२. १, ८; २४; २, ३१; ३, १; ६; ४, २४; १३. २, ३९; १४. २, १; ३२; ५०; १८. ३, ५७; १९.

६, ९; २२, २१; २३, ३०; ३१, ९; ३५, १; ४१, १; ५२, १; ५३, १०; ५६, २.

अघऽअश्वस्य १०. ४, १०.

अघऽकृते १०. १, ५.

अघकृत्ऽभिः १४. २, ६२.

अघऽद्विष्टा २. ७, १.

अघम् १. २८, ३; ४. १७, ३; ३३, १[२]; २; ३; ४; ५; ६; ७; ८; ८. ४, २; ६, २६; १०. १, ५; १२. ३, १४; ८, ५; १४. २, ५९; ६०; ६१; ६२; २०. २०, ६; ५७, ९.

अघऽमारः ६. ९३, १.

अघऽयताम् १०. ९, १.

अघऽयन्तम् १०. ४, १०.

अघऽयवः १. २७, २; ३; १९. १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०.

अघऽयुः ४. ३, २; ५. ६, १०; १०, १; २; ३; ४; ५; ६; ७; १९. ४७, ७; ४९, ९.

अघऽयूनाम् १. २०, २.

अघऽयोः १. २७, १; ७. ५३, १; २०. १७, ११; ८९, ११; ९४, ११.

अघऽरुदः ८. १, १९; ११. २, ११.

अघलाः ८. ८, १०.

अघऽविषा ५. १८, ३; १२. ७, १; १५; १०, १३.

अघऽविषाः ६. ९३, २.

अघऽविषाभ्यः ६. ९३, ३.

अघऽशंसः ४. २१, ७; ७. ७९, १; १९. ४७, ६.

अघशंसऽदुःशंसाभ्याम् १२. २, २.

अघऽशंसम् ८. ३, १९; ४, २.

अघऽशंसाय ८. ४, ४.

अघऽहारः ६. ६६, १.

अघात् १२. १०, १३.

अघार्य २०. ३७, ७.

अघारिणीः ११. ११, १४.

अघोरऽचक्षुः १४. २, १७.

अघोरेण ७. ६२, १; १४. २, १२.

अघ्नत ८. १२, १; ३; ५; ७; ११. ७, १९.

अघ्न्यः ९. ४, १७.

अघ्न्या ३. ३०, १; ६. ९१, २; ७. ७७, ८; ९. १५, ५; १९. १६, २; २७, १५.

अघ्न्याः ७. ८८, २; ८. ७, २५; १९. ४४, ९.

अघ्न्यानाम् ९. ४, २; ४; १९.

अघ्न्यायाः ८. ३, १५.

अघ्न्ये १२. १०, १२; १४.

अघ्न्ये ६. ७०, १; २; ३; ७. ७७, ११; ९. १५, २०; १०. ९, ३; ११; २४; १०, १; १२. ११, २; ४; १८. ३, ४.

अघ्न्यौ १४. २, १६; १८. ४, ४९.

अङ्कान् १. १२, २.

अङ्किनः १९. ६६, १.

अङ्कुशः ६. ८२, ३; २०. ५, ४.

अङ्कुशम् २०. ९४, ९.

अङ्केन ७. १२०, १.

अङ्क्ऽम् ६. ६९, २; ९. १, १९.

अङ्ग १. १६, २; २. ३, २[२]; ५. ११, ५; ७; ९. १४, ५; ११. ६, २१; १३. ३, २१; २०. २०, ५; ५७, ८; ६३, ४; ५; ६; ८९, ३; १२५, २; १२६, ७.

अङ्गऽज्वरः ५. ३०, ९.

अङ्गऽज्वरम् ५. ३०, ८; ९. १३, ५.

अङ्गऽभेदः ५. ३०, ९; १९. ४४, २.

अङ्गऽभेदम् ९. १३, ५; २२.

अङ्गम् ५. १७, ५; ६. ७२, १; १०. ७, २; ९; २५; २६; १४. १, २७; १८. २, २६; ४, ६४.

अङ्गम्ऽअङ्गम् ४. ९, ४; ९. ३, १०.
अङ्गा ६. ६६, ३; ११. १०, १२; १२. ९, ४; ११, १०.
अङ्गात् १०. ७, २[३].
अङ्गात्ऽअङ्गात् ५. २९, १; ८. ७, ३; १०. ४, २९; १४. २, ६९.
अङ्गानाम् १८. २, २४.
अङ्गानि ३. २, ५; ११, ६; ४. ५, ४; १२, ७; ६. ९०, २; ९. ४, ११; १३, १९; १०. ५, ५०; ७, १८; ११. ९, ६.
अङ्गिरः २०. १०३, ३.
अङ्गिरःऽभिः २. १२, ४; १८. १, ४७; ५९; ६०; २०. ७७, ८.
अङ्गिरःऽभ्यः १२. ३, ४४; १९. २२, १८; २०. २८, २; ३९, ३.
अङ्गिरसः २. १२, ५; ३. २१, ८; ८. ८, १३; ९. ५, १६; १०. ६, २०; ७, १८; ३४; ११. ८, १३; १२. ३, ४३; ४५; १८. १, ५८; ६१; ३, २०; ४, ३; २०. ९१, २.
अङ्गिरसम् ४. २९, ३.
अङ्गिरसाम् ६. ३५, ३; १६. ८, १४; १८. ४, ८.
अङ्गिराः १९. ३४, ६; ५४, ५; २०. २५, ४.
अङ्गिरेभ्यः १९. ३९, ५.
अङ्गुरिम् ४. १८, ६; ५. ३१, ११.
अङ्गुलिऽभिः ४. १४, ७.
अङ्गुलिऽभ्यः २. ३३, ६; २०. ९६, २२.
अङ्गुलीः १०. २, १.
अङ्गे १०. ७, १[३]; ३[४]; १३; २७.
अङ्गेऽअङ्गे १. १२, २; २. ३३, ७; ६. ११२, ३; २०. ९६, २३.
अङ्गेन ६. ७२, १.
अङ्गेभ्यः १. १२, ४; २. ३४, ५; ३. ७, ३; ५. २२, १४; ३०, ८; ६. ९०, १; ९. १३, ७; ८; ९; ११. २, ६; १९. ४४, २.
अङ्गेऽस्थाः ६. १४, १.
अङ्गैः ४. १४, ९; ६. १२०, ३; ७. ५, ५; ८. २, ३.
अङ्गो इति ६. ६०, २.
अङ्घ्रि ३. १२, ८; ४. १५, ६; १२. ३, ४५; १९. ३१, १३.
अङ्ग्यः ६. १२७, ३.
अच ४. १५, १६.
अचक्रुषे ५. १४, ९.
अचति १०. ८, २९.
अचरत् ६. ९२, २.
अचरत् ५. ४, ४; ६. ९५, २; १०. १०, १९; १३. २, ४१; १९. ३९, ७.
अचर्कृषुः ६. ३०, १; ९१, १.
अचलत् १५. २, १; ९; १५; २१; ६, १; ४; ७; १०; १३; १६; १९; २२[२]; २४; ९, १.
अचस्व ३. ३, १.
अचाकशम् २०. १२६, १९.
अचामि १४. १, ३८.
अचायिषम् ७. ९४, १; १०. ५, ४६.
अचिकित्वान् ९. १४, ७.
अचिकित्सीः ५. ११, १.
अचिक्रदत् ३. ३, १.
अचिक्रदत् १८. ४, ५८; २०. ३१, ५.
अचितः ८. ४, १.
अचितम् ८. ३, २१.
अचित्तीः २. ६, ५.
अचित्त्या ५. १७, १२; १३; १४; १५; १६;

१७; ३०, ३; ३१, १०; ६. ५१, ३; १२. ४, ५१; ५२.
अचिन्वन् १०. २, ४.
अचीक्लृपत् ६. ११, ३.
अचीचरत् १२. ४, २८.
अचेतयत् २०. ११, ५.
अच्छ ३. ४, ३; २०, २; ५. २७, ४; ६. ३९, २; ११. १, २; १३. २, ४६; १९. २, ३; २०. १२, ४; १७, १; २४, ३; ३६, ५; ४६, १; ३; ७०, २; १०३, ३; १४३, ५.
अच्छऽआयन्ति १२. ४, १४; १५.
अच्छऽआवदामसि ७. ३९, ३; ८. ७, १; १०. १०, ४; १२. १, २७.
अच्छऽआवदामसि ६. १४२, २.
अच्छऽआवदामि ६. ५९, ३.
अच्छिदन् ६. १०४, १.
अच्छिद्यमानया ७. ५०, १.
अच्छिद्यमाना ८. २, १.
अच्छिन्नः १९. ५८, १.
अच्छिन्नऽपर्णेन १९. ३२, २.
अच्छिन्नम् ६. १२२, १.
अच्छिन्नाः १९. ५८, १.
अच्छोक्तिऽभिः २०. ३५, ३.
अच्यसे ६. ४९, २.
अच्युतः ६. ८८, ३; १९. ३३, २.
अच्युतऽच्युत् ५. २०, १२; २०. ३४, ९.
अच्युतम् ५. २८, १४; १२. ३, ३५.
अच्युता ९. २, १५; २०. ३६, ६.
अज ४. ३७, २; ९. ५, ९; १६.
अज ९. ५, १५.
अजऽअवयः ५. २१, ५; ७. ६२, ५; ८. ७, २५; ११. २, ९; १९. ६, १२.
अजऽअविषु ११. २, २१; १२. २, १५.
अजः ४. १४, १; ९. ५, १; ३; ७[२]; १०; ११; १३; १६; १८; २०; २१; ३१; ३२; ३३; ३४; ३५; ३६; १०. ७, ३१; ८, ४१; १३. १, ६; १८. २, ८; १९. ११, ३.
अजगन् १९. ४९, ३.
अजगन्त २०. १३७, १.
अजगन्तन २०. १२६, २२.
अजगराः ४. १५, ७; ९; ११. २, २५.
अजग्धऽपाप्मा ९. ७, ९.
अजग्रभम् ४. ५, ४[३].
अजत् ३. ८, ४.
अजतु २. १४, ४; ७. १०, ४; ८. ६, १९.
अजनयत् ६. ७८, ३; १५. १, २; १९. ३६, ४; ५३, ५; ५४, ३.
अजनयन् १९. २७, ७; ३४, ६; ५२, ३.
अजनयन्त १३. ३, १२; २३.
अजनयन्त ९. १, ५.
अजनयम् ६. ६१, २; ३.
अजनि २०. २५, ५; ११५, १.
अजनिष्ट ४. १४, १; ९. ५, १३.
अजनिष्ट ६. ११०, ३; ७. १०, १; १२. ३, ४७.
अजनिष्ठाः ११. १, ३.
अजन्तु ८. ५, ५; ६; १४. १, ३९.
अजऽबभ्रु ५. ५, ८.
अजम् ४. १४, ६; ९; ९. ५, ७[२]; ११; १२; २२; २४; २५; २६; २७; २८; ३१; ३२; ३३; ३४; ३५; ३६; ३७; १८. २, ९.
अजयः २०. २९, ३.
अजयत् ७. ६४, १; ८. ५, ३[२]; १४; १०. ६, ९; १०; १३; १९. १३, २; २०. ९०, ३.

अजयन् १०. ६, १६; ११. १२, १२.
अजरः ८. ३, २०; १९. २४, ८; ५३, १; २०. ३६, ३.
अजरन्तीम् ७. ६, २.
अजरम् ३. १९, १; ५; ६. ९८, २; ९. १४, २; १४; १०. ८, ४४; १३. ३, १८; १८. ४, ८८; २०. १०५, ३.
अजरा १०. ८, २६.
अजराम् २. २९, ७; १२. २, ३२.
अजरासः ८. ३, १९.
अजरे इति ८. ३, २५; ९, १२.
अजरेभिः ८. ४, ५.
अजऽश्रृङ्गि ४. ३७, २.
अजऽशृङ्गी ४. ३७, ६.
अजर्य ४. ४, ८; १४, ७; ८; ९. ५, १९; १४, ७.
अजस्रः ७. ८३, १; १९. ३, २.
अजस्रम् ६. ३६, १; १३. २, ३६; १६. २, ५.
अजस्रा १८. १, ३५.
अजहात् १८. २, ३३; ४, ६४.
अजाताः ११. १०, ५.
अजातान् ६. १३६, २; ७. ३५, १; ३६, १.
अजानन् ९. ५, १६; १४. १, १५.
अजानये ६. ६०, १.
अजानात् ११. १०, १७.
अजाम् ६. ७१, १.
अजामसि २. १४, २; १२. २, २; ३.
अजामि १८. १, १०; ११.
अजामि ३. २५, ५.
अजायत ६. ३४, ५; १२. १, ५७; ४, २४.
अजायत २. २५, २; ६. ३९, ३; ५८, ३; १०. ४, ७; १०, १८; १९; ११. १०, ८[२]; ९[२]; १३. १, ४८; ५५; ३, २६; ७, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६; ७[२]; ८[२]; ९; १०; ११[२]; १५. १, ३; ८, १; १८. १, २१; १९. ६, ६; ७[२]; १३; ३०, ५; ३९, ६; ७; ८; ५३, १०; ५४, ३;
अजायथाः ५. ४, १; ७. ८९, २.
अजायथाः ४. १९, ४; २०. २६, ६; ४७, १२; ६९, ४; ११.
अजायन्त ११. १०, ३; १३. ७, ६; ९; १०; १९. ६, १२; १६.
अजाविऽभिः १०. ६, २३.
अजिनम् ६. ६७, ३.
अजिनेन ५. २१, ७.
अजिनैः ४. ७, ६.
अजिरऽअधिराजौ ७. ७३, ३.
अजिरः ३. ४, ३.
अजिरम् ८. ८, ३.
अजिरऽयते २०. २८, ४; ३९, ५.
अजीगमत् ६. ३२, २; ७४, १.
अजीगमम् २. २५, ५; ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८.
अजीगरिति २०. ७६, १.
अजीजनः ५. ११, ११.
अजीजनन् ११. १, ३.
अजीजभम् ७. ५८, ५.
अजीतः १२. १, ११.
अजीता १. २७, ४.
अजीवनः १८. २, ३०.
अजीहिडत् १२. ४, ८.
अजुरम् २०. ८५, २.
अजुर्य २०. ३६, ९.
अजुर्यम् ५. १, ४.

अजुषे ६. ६१, ३.
अजुष्टा ७. १२०, २.
अजुष्टानि ६. ४५, २.
अजुष्टाम् १०. ३, ६.
अजे ५. ३१, २.
अजे ५. ११, २.
अजेन १८. २, २२.
अजैत् १२. ३, ५४.
अजैषम् २. १४, ६; ७. ५२, ५[२]; ८.५, ८.
अजैषीत् १४. २, ७४.
अजैष्म १६. ६, १.
अजोषाः २०. ७१, १०.
अज्ञातः १०. १, ८.
अज्ञातम् ६. १२७, ३.
अज्ञातऽयक्ष्मात् ३. ११, १; २०. ९६, ६.
अज्ञाताः ८. ७, १८; २०. ७९, २.
अज्ञाते १०. १, २०.
अज्ञास्थाः ३. ४, ६.
अज्म ६. ९७, ३; १९. १३, ६.
अज्मना ११. १२, २२.
अज्मनि ११. १२, २२.
अज्यते १४. १, २६.
अज्यसे २०. ६, ६.
अज्यानिम् ६. ५५, १.
अज्रान् २०. ६१, ५; ६२, ९; ९४, ८.
अञ्चतु ११. १२, १६.
अञ्जः २. ५, ६.
अञ्जःऽयानैः १८. २, ५३.
अञ्जत् १९. ५३, २.
अञ्जते १८. ३, १८.
अञ्जते १८. ३, १८[३].
अञ्जन्तु १८. ३, १०.
अञ्जन्तु ३. २२, २.

अञ्जिऽवम् ८. ६, ९.
अञ्जिषु २०. ६७, ४.
अञ्जे २०. ३९, ५.
अणीयःऽकम् १०. ८, २५.
अणूनि ११. ९, १०.
अण्वीभिः २०. ८४, १.
अतः ५. २, ६; २२, ११; ६. १११, १; ८. १, ४; ९. ५, ६; १५. १०, ३; ४; ५; १८. १, ३२; ५५; २०. २१, ३; ७०, ५; ७७, ५; ८८, ३; १०७, ९; १४०, ५.
अतनुत १०. २, १६; १८. ३, ४१.
अतन्द्रः ११. ६, २४; १३. २, २८; ४२.
अतन्द्राः २०. १८, ३.
अतन्वत ७. ५, ४; १९. ६, १०.
अतपत् १३. २, ४०.
अतप्तः ९. ५, ६.
अतरन् ४. ३५, २.
अतर्पयत् ८. ९, २४.
अतसि २०. ४५, १.
अतसीनाम् २०. ५०, १.
अतस्करम् १२. १, ४७.
अतान् ९. ४, १.
अतारीत् १३. २, ३४; २०. १०७, १३.
अति २. ६, ५[४]; ११, १; २; ३; ४; ५; ३. ११, ३; ४. ५, २[२]; १६, ४; ६; ३३, ७; ८; ३४, ४; ३५, १; २[२]; ३; ४; ५; ६; ५. ८, ४; २८, १२; ६. ३४, १; २; ३; ४; ५; ५१, १; ७५, ३[२]; ११०, २; ७. ४२, १[२]; ६५, १[२]; १२२, १; ८. ५, ९; ९, २६; ९. ५, ९; १०. १, १६; ५, १५; १६; १७; १८; १९; २०; २१; ८, १६; ९, ८; ९; १०, १५; ११. १, १२; २१; ३, २५; १२. २, ११; ३, १८; १३. १,

३६; ४५; २, ५; ३४; ४०; **१४.** २, ११; ७४; **१५.** १२, २; **१६.** १, ४; ७; **१७.** १, २५^{2}; २६^{2}; **१८.** १, २४; ३३; ३८; ३९; २, ११; ३२; ३८; ३, १७; **१९.** ६, १; ९; ३२, ४; ३३, ३; ३६, २; ४९, २; ५०, २; **२०.** १२, २; ३१, ३; ३६, ७; ४६, २; ५७, ३; ६८, ३; ७९, २; ९२, ११^{2}; ९४, १; ९६, ८; १०७, १३; १२६, २.

अतिऽअमन्यन्त **१०.** ८, ३९.

अतिऽआप्तिः **११.** ९, २२.

अतिऽआयन्ति **११.** १२, १४.

अतिऽआयन्तु **११.** १२, १५.

अतिऽआयम् **१०.** ८, ३.

अतिऽइव **२.** १२, ६.

अतिऽएषि **१३.** १, ५७.

अतिऽक्रामन्तः **१२.** २, २८; २९.

अतिऽघ्न्याः **११.** ९, १६.

अतिऽजीवः **८.** २, २६.

अतिऽतार्याः **८.** २, २७.

अतित्रसन् **५.** २१, ७.

अतिथयः **९.** ७, ६.

अतिथिः **७.** २२, १; ७७, ९; **९.** ७, ४; ८, ७; **१०.** ६, ४; **१५.** १०, १; ११, १; १२, २; १३, १; ३; ५; ७; ९; ११.

अतिथिऽग्वम् **२०.** २१, १०.

अतिथिऽग्वस्य **२०.** २१, ८.

अतिथिऽग्वाय **२०.** ३७, ८.

अतिथिनीः **२०.** १६, ३.

अतिथिऽपतिः **९.** ६, ३; ७, १; ११, ५.

अतिथीन् **९.** ६, ३; १०, ८; ११, ५.

अतिथीनाम् **९.** ७, १३.

अतिथेः **९.** ८, १; २; ३; ४; ५; ६.

अतिथौ **९.** ८, ८.

अतिऽदीवा **७.** ५२, ६; **२०.** ८९, ९.

अतिऽनुत्तः **८.** ७, १९.

अतिऽपश्यम् **११.** २, १७.

अतिऽभाति **१०.** ३, १७.

अतिऽमात्रम् **५.** १९, १; **८.** ६, १३.

अतिरः **२०.** ९३, ६; १३७, ११.

अतिरत् **५.** १८, ११; **२०.** ११, १; ५; २८, १; ३९, २.

अतिऽरात्रम् **१०.** ९, ९.

अतिऽरात्रेण **९.** ९, ४.

अतिऽरिक्तः **८.** ९, १७.

अतिऽरोचते **६.** ३४, ३.

अतिविद्धऽभेषजी **६.** १०९, १.

अतिऽविध्यन्ति **८.** ५, १९.

अतिऽशर्वरे **४.** ५, ४.

अतिऽशर्वरेषु **७.** ८५, ४.

अतिष्ठः **१०.** १०, १६.

अतिष्ठत् **९.** १४, ९.

अतिष्ठत् **३.** १३, ४; **८.** ११, १; **११.** ७, ५; २६; **१५.** २, १; ९; १५; २१; ३, १; **१९.** ६, १; **२०.** १३७, ७.

अतिष्ठताम् **१५.** १०, ३.

अतिष्ठन् **५.** २७, ६; **१०.** ८, ३९.

अतिष्ठिपम् **६.** ७७, १; **७.** १००, २; १०१, १.

अतिऽसक्ता **१२.** ३, २३.

अतिऽसराः **५.** ८, २; ४.

अतिऽसरान् **५.** ८, ७.

अतिऽसर्पति **४.** २०, ९.

अतिऽसर्पात् **४.** १६, ४.

अतिऽसृजेत् **१५.** १२, ३^{2}.

अतिऽसृष्टः **१५.** १२, ४; ७; **१६.** १, १.

अतिऽसृष्टाः १६. १, १.
अतिऽस्थाय १९. ३३, ५.
अतिस्थाऽवान् ३. २२, ६.
अतिऽहितम् ७. ५५, ३; १८. २, २६.
अतीतरः ११. ६, ६.
अतीतृपः १२. ३, ३६.
अतुराणाम् ७. ५२, २.
अतूर्तम् २०. १०५, ३.
अतृणत् १९. ३२, ४.
अतृपम् ३. १३, ६.
अतृष्याः ७. ६२, ४; ६.
अतृहम् २. ३१, २^{२}.
अतेजसम् २. १९, ५; २०, ५; २१, ५; २२, ५; २३, ५;
अत्त २. २४, १^{३}; २^{३}; ३^{३}; ४^{३}; ५^{३}; ६^{३}; ७^{३}; ८^{३}.
अत्तम् ६. १४०, २^{२}.
अत्तवे १. ११, ४; ५. १८, १; १२. २, ३७; १४. १, २९; १८. १, ५६; ५७; २, ३४.
अत्तारः ६. १४२, ३.
अत्ति ९. १४, २०.
अत्ति ४. ३०, ४; १२. ९, ३; १५. १४, २; ४; ६; ८; १०; १२; १४; १६; १८; २०; २२; २४.
अत्तु १. २८, ३; ४; ४. १७, ३; १८. ३, ४६.
अत्तुम् १८. ४, ६३.
अत्तो इति १८. ३, ४४.
अत्त्रिः १३. २, ४; १२; ३६; ३, १५; १८. ३, १५; १६.
अत्त्रिणः १. ७, ३; १६, १; ३; २. ४, ३; ४. १०, २; ६. ३२, ३; ८. ४, १; ५.
अत्त्रिणम् २०. ६३, ७.
अत्त्रिणाम् १. ८, ४.
अत्त्रिम् ४. २९, ३; ४.
अत्त्रिऽवत् २. ३२, ३; ५. २३, १०.
अत्नत २०. ११०, ३.
अत्ऽभिः २. १०, २; ४. २७, ४; ५; १२. ३, ३०; १५. १४, ६; १८. १, ५५.
अत्ऽभुतम् ५. २७, १०.
अत्ऽभ्यः ३. ३, ३; १०. ५, ३३; १३. ७, ९; १५. २, १७; १९. ४३, ७.
अत्यः २०. ३१, ५.
अत्यान् २०. ११, ९.
अत्र ३. २३, २; ४. ७, ७; ५. १, ३; ५; ६, २; ८, ९^{२}; ६. ३७, २; ५३, ३; १०४, २; १२३, २; ८. १, ९; ९. ४, २४; १४, १; ७; १३; २२; १५, १२^{२}; ११. १, ३३; १२. २, १; १०; १८; २६; २७; ३, १७; ४५; ४८; ५५; ५६; ५७; ५८; ५९; ६०; १४. १, ५८; १७. १, ८; १८. १, १३; २६; ३१; ३४; ३६; ३९; ४३; २, ३०; ५९; ३, ६; ५१; ७३; ४, ७; ३३; ४७; ४९; ८६^{२}; १९. ७, ३; २०. ४१, ३; ८९, ४.
अत्रयः १८. ३, २०.
अत्राः ९. १२, १६; १०. १०, २१.
अर्थ १. ७, ३; ७; १८, १; २. ६, ५; ३. ३, ६; ८, १; १२, ५; २५, ६; ४. १, ५; ४, ८; ७, २; १७, ८; ६. ५०, १; ६६, ३; ११६, १; ११९, २; १२१, १; १२८, २; ७. ९, १; १५, ३; ५८, ६; ८८, ४; ८. १, ६; ८, २०; ९, २४; ९. ५, २७; १४, १२; १०. १, २८; ४, १; ११. १, ८; ६, १४; १०, ३१; १२. २, ३०; ३, ५५; ५६; ५७; ५८; ५९; ६०; ४, २२; २३; २५; २८; ३६; ५२; १४. १, १६; २१; २, २९; १५. १२, ८; १३, ११;

१८. २, ४; ५^{२}; ९; ३, ७१; १९. ३४, ८; ५२, ५; ६८, १; २०. ११, १०; ५६, ५; ५७, ३; ६८, ३; ७३, ४; ८७, ५; १४१, ४.

अथर्वऽअङ्गिरसः १०. ७, २०.

अथर्वणः १०. २, २७.

अथर्वणाम् १६. ८, १६.

अथर्वणि २०. १४०, २.

अथर्वणे ७. १०९, १.

अथर्वन् ५. ११, २.

अथर्वऽवत् ८. ३, २१.

अथर्वा ५. २, ९; १०. २, २६; १०, १२; १७; १८. ३, ५४; १९. ४, १; ५४, ५; २०. २५, ५; १०७, १२.

अथर्वाणः ४. ३७, १; १०. ६, २०; ११. ८, १३; १८. १, ५८.

अथर्वाणम् ४. १, ७; ५. ११, ११; ७. २, १.

अथो इति १. १४, २^{२}; २२, २; ४; २. ४, ६^{२}; ९, १; ३१, २; ४; ३२, ५; ३६, ७; ३. २, ४^{२}; १८, ५; २१, ९; २४, १; २५, ५; ४. ३, ४^{२}; ४, ५; ६, ६; ९, ३^{२}; १३, ५; १७, ७; १९, ३; २०, ५; ३६, १; ५. १४, २; २१, ४; ५; ६; २२, १०; २३, १२; ३०, १३; ६. १३, १; १४, ३; १९, २; २१, ३; ६९, ३^{२}; ७४, २^{२}; ९६, २^{२}; १०३, २; १०९, ३; १२८, ४; १३३, ४; १३८, २; १३९, २^{३}; ४; १४०, २^{२}; ७. ५८, २; ५; ६२, ५; ७८, ३; ८०, २; १००, ३; ११७, २^{२}; ८. २, २८; ५, १२^{३}; ७, ५; १०; २२; २८^{२}; ९. ३, १; ४, ४; २०; १३, ७; १५, २८; १०. २, २७; ३, ७; ८, २२; ३८; ९, १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १०, १७; ३३; ११. १, २९; ६, ३; ९; १७; ८, २; ६; ७; ९, ८; १०, ५; १४; १५; २३; ११, १०; २२; १२, ३; १२. १, ७; ९; २, १९; ४, १८; ३०; ३९; ४०; ४६; १४. १, २; २८; २, ४; १९. ४, ३^{२}; ६, ९; ३४, ४^{२}; ३९, २; ३; ४; ४६, ३; ४८, १; ४९, ३; ५०, ५; २०. २०, ४; ३२, ३; ५७, ७.

अदः २. ३, १; ३. ७, ३; १३, १; ४. २, ४; १९, ४; ५. २, ३; ६. १८, ३; १०. ९, ५; ११. १०, ३३^{२}; १३. १, ५५; १९. ५२, ४; २०. १०७, ६.

अदःऽअदः १६. ७, ९.

अदत् १०. ८, २२.

अदत्त २. ५, ७; १०. ८, २१; १५. १, ६; १९. ४६, ३.

अदत्तः ५. ११, ९; १०.

अदत्ता १२. ४, १३.

अदत्त्वा १२. ४, १९; २३; ४५.

अददत् १२. ४, २०; २१; २६; ३४.

अददन्त १४. १, ४५.

अददात् १२. ४, ५०; १४. १, ९.

अददुः ५. १७, १०^{२}; १८, १.

अददुषः १२. ४, ४८.

अददुषे १२. ४, ३९.

अदधाः २०. २५, ३.

अदधात् १०. २, ७; १३. ३, २२.

अदधात् १०. २, ११; १२; १४; १५; १७; ११. १०, १४; १५; १३. १, १४; १४. १, ५३.

अदधुः १८. १, ३५; १९. ६, ५; २०. १६, ११.

अदधुः ४. ३०, २; ८. ९, १४; ९. ४, १६; १०. २, २; ४; १८. २, ३३; ४, ७; १९. ५६, ४.
अदन्ति ७. ५८, ७; ८. ६, २३.
अदन्तु ११. १२, २६.
अदन्तु ५. १२, ११; ८. ३, ७; ११. १२, २३; २४.
अदब्धः ६. ५३, २; १७. १, १२.
अदब्धऽअसुः ५. १, १.
अदब्धऽचक्षुः १३. २, ४४.
अदब्धम् २०. ८८, २.
अदब्धेन १७. १, १२.
अदब्धेभिः १७. १, ९.
अदर्दरित्यदर्दः २०. ९१, ७.
अदहत् १. २५, १.
अदाः १८. ३, ४२; ४, ६५.
अदात् ३. २९, ७[2]. ६. १००, १[3]; १२. ४, ४९; १४. १, ५२; २, २; ४.
अदान् ६. ५०, १.
अदानाय १२. ४, ५१.
अदान्यान् २. ३५, ३.
अदाभ्यः ३. २१, ४; ७. २७, ५; १८. १, १८.
अदाभ्यम् ८. ४, २०; २०. ५८, ४.
अदायः १९. १३, ७.
अदारऽसृत् १. २०, १.
अदाशन् २०. ३७, ९.
अदाशुषः २०. ३७, १.
अदाशुषाम् २०. ५६, ६.
अदास्यन् ६. ७१, ३; ११९, १.
अदितये ५. १२, ४; ७. ३५, १; ८८, ३; ८. ३, १६; १८. ४, ६९.
अदितिः ३. २२, १; ५. २६, ६; ६. ३, १; ४, १; २; ७, १; ६८, २; ८१, ३; १२०, २; ७. ६, १[6]; १८, ३; ८. ९, २१; ९. १२, १०; ११. १, १; ११; ३, ४; १२ १, ६१; १५. ६, २०; १८, ४; १८. १, १९; ३६; ३, २७; १९. १०, ९.
अदितिम् ३. ८, २; ७. ६, २; ७, १; २; १८. ४, ३०.
अदिते २. २८, ५; १२. ३, ११.
अदितेः २. २८, ४; ३. १६, २; ७. ८, १; ११. १, २४; १३. २, ९; १५. ६, २१; १८. १, १८.
अदित्याः ३. २२, १; ५. १, ९; १३. १, ३८; २, ३७.
अदित्सन्तम् ३. २०, ८.
अदिद्युतत् ७. १५, २.
अदिप्सतः ४. ३६, २.
अदिषि १. १४, १; १३. १, ३०.
अदिहन् ४. ६, ७.
अदीधरत् ६. ८७, ३.
अदीधरन् ३. ३, ५.
अदीव्यन् ६. ११९, १.
अदुः ५. २५, ९; ११. १, १७.
अदुः २. ३६, ७; ३. २२, १; ६. १००, १[2]; १४. १, ५०; १९. ३०, २.
अदुःऽकृतौ १४. २, १६.
अदुःमङ्गली १४. २, ४०.
अदुग्धाःऽइव २०. १२१, १.
अदुहत् ७. १६, १.
अदुहत् २. १, १.
अदुहन् ८. ११, ७.
अदूदुषत् २०. १२६, ५.
अदूदुषम् ४. १८, ५; १०. १, ४.
अदूनाः २. ३१, ३.

अदृंहत् १३. १, ६; १९. ३२, ९; २०. ३४, २.
अदृंहत् १३. १, ७.
अदृंहयत ४. ११, ७.
अदृश्यमानः १०. ८, १३.
अदृश्रन् १३. २, १८; २०. ४७, १५.
अदृष्टः ५. २३, ७.
अदृष्टम् २. ३१, २.
अदृष्टऽहा ५. २३, ६; ६. ५२, १.
अदृष्टाः ६. ५२, २.
अदृष्टान् ५. २३, ६; ६. ५२, ३; ८. ८, १५.
अदेवः ६. ६, १; २०. ३६, ११.
अदेवः ५. ८, ३.
अदेवीः ८. ३, २४; २०. ८७, ५; १३७, ९.
अदेवृऽघ्नी १४. २, १८.
अदोमदम् ६. ६३, १.
अदोमधौ ८. २, १८.
अद्गाःऽइव १. २७, ३.
अद्धा २०. ५८, ३.
अद्धातयः ११. १०, ७; १४. १, १६.
अद्धातिः ६. ७६, २.
अद्भिः ७. ७७, ११; ९. १५, २०; १८.४, ६५.
अद्भिः ४. २२, ७; ५. २२, ८; ६. ६३, १; १२. २, ३; १८. ३, ४२.
अद्भुतः २. १२, १.
अद्मसि ६. १६, १.
अद्मि ६. ७१, १; ३.
अद्मि ५. १८, ७; १४. १, ५७; २०. १२६, १४.
अद्य १. १, १; २०, २; ३२, ३; ३. २, ४; २२, ३; ४. ३, ५; ४, ६[४]; ५. ७, ५; ६; १२, १; ९; १८, २; ६. ६६, २; ६७, १; ९०, १; ९९, २; १०८, ४; ११८, १; १३८, १; ७. २१, १; ३२, १; ४९, २; ५०, २; ५२, १; ८७, ६; ८९, १; १०२, १; ८. ३, १२; १४; ४, १५; ९. १५, ९; १०. ५, ४८; ७, २३; ८, २३; २९; १०, ११; ११. ६, २१; १०, ३; १६; १२, २०; १२. २, २२; १३. १, ५८; १६. ४, ६; ६, १[२]; १८. १, ६; ४६; २, १३; ३, ५९; १९. ११, ५; ४७, ५; ६; ४९, ९; ५०, २; ६; २०. ६१, ३; ७७, २; ९६, २; ९७, १; ९९, २; ११२, १; १४०, ४; १४१, ३; १४३, १; ३.
अद्यात् ५. १८, २.
अद्योतयन् ४. २३, ५.
अद्रयः २०. २३, २; ३३, १.
अद्रिः ५. २०, १०; ९. ४, ५; १९. १०, ३; २०. ११७, १.
अद्रिऽदुग्धाः २०. ८८, ३.
अद्रिऽभित् २०. ९०, १.
अद्रिम् २०. १६, ११; ३५, ७; ३८, ६; ४७, ६; ७०, ९; ७७, ८.
अद्रिऽवः २०. २०, ४; २३, १; ५७, ७; ६१, १; ९३, १; ९८, २; १००, २; ११६, १.
अद्रुहः ६. ७, १; २०. ५४, ३.
अद्रूक्षणम् ८. २, १६.
अद्रोघऽअविता ११. १, २.
अद्रोघऽवाचम् ६. १, २; २०. ३६, २.
अध १. २८, ४; ३. ४, ४; २०, १; ४. ३२, ७; ५. २२, २[२]; ६. ६५, १; ७. ७७, ११; ८८, ३; ८. ४, १५; ९. १६, २०; १०. २, ७; ४, २५; १२. ३, २; ९; १३. १, ३०; १४. २, २०; १८. १, १६; २१[२]; ५१; २, ११; २३; ३, १७; २१; ४, ४८; ६३; ६९; ७०; १९. ३३, ५; ४७, ८; ५०, १; २०.

१५, २; २४, ६; ६०, २; ८३, २; ९२, १३; १००, १; १०८, २; १३७, ९.
अधः ३. १८, ४; ६. ४२, २; ८. ४, ११.
अधःऽपदम् २. ७, २; ५. ८, ५; ८; ७. ३५, १; ६४, १; ११. १, १२; २१.
अधःऽपदे॑न १०.४,२४.
अधःऽव॑र्चसः ५. ११, ६.
अधत्त १३. १, ४६; २०.१३७, ७.
अधमः ८. ४, १६.
अधमत् २०. ८८, ४.
अधमम् १. २१, २; २. ८, १; ३. ७, ४; ७. ८८, ३; ८. २, २४; ९. २, १७; १८; १०. ३, ९; १३. १, ३२; १८. ४, ६९.
अधमा ९. २, ४; ९.
अधमाः ६. १२१, १; ७. ८८, ४.
अध॑रः ७. ३२, १; १९. ४६, ५.
अध॑रःऽअधरः ६. १३४, २.
अध॑रम् २०. ३४, ४.
अध॑रस्याः ८. २, १५.
अधरऽहनुः ९. १२, २.
अध॑रा ३.१८, ४.
अधराङ् ५. २२, २; १२. २, १.
अधरा॑चः २०. ९५, ३; १२५, १.
अधराच्य॑म् ४. ७, २.
अधरा॑ञ्चः ३. ६, ७; ९. २, १२.
अधरा॑ञ्चम् ५. २२, ३; ४; ६. १२७, ३; १०. ५, ३६; १६. ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; १९. ३९, १०.
अध॑रात् ७. ५३, १; २०. १७, ११; ८९, ११; ९४, ११.
अधरात् २. १४, ३; ६. ४०, ३; ८. ३, १९; २०; ४, १९; ५, १७; ११. २, ४; १२. १, ३१; ३२; २, ४१; १८. ४, ११; १९. १५, ५; ४८, ४.
अध॑रान् २. ३९, ३; ३. ६, ६; ५. ८, ८; २८, १४; ६. ८८, ३; १०. ३, ३; ६, १९; ३०; १३. १, ३१; १९. ३३, २.
अध॑राभ्यः ३. १८, ४.
अध॑रे १. ९, २; ४; ३. १९, ३; ४. २२, ६; १३. १, ३१.
अध॑रौ १०. २, २.
अधस्ता॑त् ४. ४०, ५.
अधात् ९. १५, १२. १०. ४, २६; ५, ४३; १२. २, ६.
अधाताम् २. २९, ५; १८. ३, १२.
अधाम् ३. १८, ६[२]; ७. ३६, २.
अधायि २०. ७६, १.
अधा॑रयत् १०. ७, ७; २०. १३७, ९.
अधारयत् १०. १०, २५; १३. २, १२; २०. ९४, ८.
अधारयत ४. ११, ७.
अधा॑रयन् १८. ३, ६८; ४, २५; १९. २४, १.
अधारयन् ३. ९, २; ५. १९, १३; १४; ९. ४, १६; १४. २, ५३; ५४; ५५; ५६; ५७; ५८.
अधि॑ १. ३, ६; ९; ९, २; ४; १४, १; १६, १; २; २४, ४; ३२, ४; ३४, १; ३५, ३; २. १, ५; ३, १; ४; ५; ७, १; ३; ९, १; ३[२]; ४; १०, ८; १४, ४; २७, ७; ३०, १; ३३, १; ४; ३. ६, १; ७, १; १२, ६; २६, १; २; ३; ४; ५; ६; ४. २, ६; ४, ७; ६, ४; ७, १; ८, २; ४; १०, २; ६; १९, ४; ७; २७, १; २८, ७; ३४, १; ५. ४, ७; ६, ४; १२, ६; २०, १०; २१, ४; २५, ८;

३०, ६; **६.** ५, ३; ७, २; २१, १; ३०, १; ६३, ३; ७०, १; २; ३^{२}; ७३, ३; ७६, १; ८४, ४; ८७, १; ३; १०१, ३; १०९, २; १११, १; ११८, ३; १२१, १; १२४, ३; १३३, ४; १३६, १; १३८, ४; ५; १४१, १; **७.** ९, १; ५५, १; ६७, १; ८७, ३; १२०, ३; **८.** २, ७; ८; २७; ६, २४^{२}; ७, २; ७; १३; १४; १६; १९; ९, ४^{२}; ५; १९; **९.** १, १०; १६; १७; ३, २०; ५, ४; ५; ६^{२}; ८; १५; १३, १२; १४, २; ३; ६; १८; २१; १५, १; ७; १८; २१; **१०.** २, ५; ७; १३; १४; १७; २६; ६, ३१; ३२; ७, १^{२}; २; १२; १५^{२}; २९; ३०; ४३; ८, १९; ४१; ९, २; १२; १०, ५; १३; १६; १९; २१; **११.** १, ४; ७; १३; १६; २४; २६; ३०; ३६; २, २०; ६, ४; ७, ११; १५; २४; ९, ८; ९; १४; १८; १०, १; ३०; ३४^{२}; ११, १०; **१२.** १, ८; ११; ५२; ५६; ५९; २, ४१; ३, १; ३; २६; ३६; ४७; **१३.** १, ११; १४; २५; ३७^{२}; ४२; २, ७; ३, २; ६; १८; २६; ७, ५; **१४.** १, १; २, ९; २३; ३७; ४३; ४८; ४९; **१८.** १, १; २, ३२; ४७; ३, ४; ४५; ४, ३; ४; **१९.** ३, १; ५, १; ६, ९; १६; २४, २; ३; २६, १; २७, १०; ३१, १२; ३४, ६; ४५, ३; ४८, ६; ५३, ३; ५४, ५; ५६, १; २; ३; ५; **२०.** ५, ५; १७, २; २२, ५; २५, ३; ३०, ४; ७०, ५; ६; ७४, ६; ९२, २; १२; ९३, ५; ९५, २; ३; ४; ९६, १७; २०; ११०, २; १११, २; १४१, ४.

अधिऽअक्षः **९.** २, ७; **१०.** १, ६.

अधिऽअक्षेण **५.** ३, १.

अधिऽअक्षेभ्यः **१.** ३१, १.

अधिऽइतीः **२.** ९, ३.

अधिऽएतिं **७.** ६२, ३; **१४.** १, ३०.

अधिऽक्षियन्ति **७.** २७, ३.

अधिऽगस्यतें **७.** १०६, १.

अधिऽगवम् **९.** ८, ९.

अधिऽचङ्क्रमाम् **११.** ११, १६.

अधिऽजानन् **९.** १४, ६.

अधिऽतिष्ठति **१०.** ८, १.

अधिऽतिष्ठन् **१३.** २, ३१; **२०.** ८६, १.

अधिथाः **२.** १३, ३; **१९.** २४, ६.

अधिऽदेवने **५.** ३१, ६; **६.** ७०, १.

अधिऽधीयमाना **१२.** ८, ३.

अधिऽनिर्दध्मसि **६.** १३८, ३.

अधिऽनिधेहि **२.** २९, २.

अधिऽपतयः **५.** २४, ६.

अधिऽपतये **६.** १०, १; २; ३; **१२.** ३, ५५; ५६; ५७; ५८; ५९; ६०.

अधिऽपतिः **३.** २७, १; २; ३; ४; ५; ६; **४.** ८, १; ३५, ६; **५.** २४, १; २; ४; ७; ८; ९; १०; ११; १२; १३; १४; ३०, १५; **७.** ५, २; **१२.** ५, ४; **१३.** २, २५; ४१.

अधिपतिऽभ्यः **३.** २७, १; २; ३; ४; ५; ६.

अधिपती इत्यधिऽपती **५.** २४, ५.

अधिपत्नी इत्यधिऽपत्नी **५.** २४, ३.

अधिऽपाः **४.** १५, १०; ३१, ५; **६.** ११९, १; **७.** ५५, २; **१०.** १, २२; **१२.** ३, ९; **१९.** ३१, २; ६; ११; ५६, ६.

अधिऽरज्जुः **६.** ११८, २.

अधिऽराजः **६.** ९८, १; २; **९.** १५, २४; **१९.** ४६, ४.

अधिऽराजम् **५.** ३, १०.

अधिऽवाकाय ६. १३, २.
अधिऽविकर्तनम् १४. १, २८.
अधिऽशोमहे १२. १, ३४.
अधिऽश्रिते १५. १२, २.
अधिऽसवने ५. २०, १०.
अधिऽस्थाता ४. १६, १.
अधिऽस्थानात् १२. ४, ४; ५.
अधिऽस्थाने १२. ४, २३.
अधिऽहिता ११. ३, १४.
अधीरः ५. ३१, १०.
अधीराः ११. ११, २२.
अधुनुथाः २०. २९, ४.
अधूषत १८. ४, ६१.
अधृष्टम् २०. ९२, १८.
अधृष्टाः १९. ५८, ४.
अधेनवे ६. ५९, १.
अधोक् ८. १३, ३^{2}; ७^{2}; ११^{2}; १५^{2}; १४, ३^{2}; ७^{2}; ११^{2}; १५^{2}.
अध्रिऽगवे २०. ३५, १.
अध्रिऽगुः २०. ९२, १६; १०५, ४.
अध्रिऽगुम् २०. ६३, ८.
अध्वऽगतः १३. १, ३६; ४३.
अध्वनः ४. ११, २; ७. ७५, २; २०. ७७, २.
अध्वऽभिः १. ४, १.
अध्वरः ४. २४, ३; ७. ६०, १; ११. ९, ७; १८. २, ३२.
अध्वरम् १. ४, २; ५. १२, २; २७, ८; ९; १४. १, ४६.
अध्वराणाम् १९. ४२, ४.
अध्वरान् १९. ५९, ३.
अध्वराय ३. १६, ६.
अध्वरिऽयताम् १. ४, १.
अध्वरे ८. ४, १८; १८. १, २१; ४१; ४, ४५; १९. ३३, ३; २०. १५, ३; १०३, ३; ११८, ३.
अध्वरेषु ५. २७, ५; ६. ११०, १; १४. १, ३७.
अध्वर्यवः २०. ८७, १.
अध्वर्युः ७. ७७, ५; १८. ४, १५; १९. ४२, १.
अध्वर्युऽभिः २०. ६७, ७.
अध्वर्यो इति ११. १, ३१; २०. ६४, ४.
अध्वा १३. २, १४.
अध्वानम् ३. १५, ४.
अन ३. ३१, ९.
अनः १४. १, १०; १२; २०. १२६, १८.
अनक्ति ५. २७, २; २०. १६, २.
अनक्तु ५. २८, ३.
अनक्तु १०. ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; १३. १, ८; १४. २, ४०; १८. ३, ११^{2}; १२; २०. १०३, २.
अनग्नाः १२. ३, ५१.
अनग्निऽदग्धाः १८. २, ३५.
अनङ्गुरेः ८. ६, २२.
अनज्मि ४. १४, ६.
अनडुत्ऽभ्यः ६. ५९, १.
अनडुहः ४. ११, ३; ८; ९; ११.
अनडुहि ४. ११, ७.
अनड्वान् ४. ११, १^{4}; २; ४; १०; ५. १७, १८; ८. ५, ११; ९. १, २२; ११. ६, १३; ७, १८; १२. ३, ४९; १९. ३९, ४.
अनड्वाहः १९. ५०, २.
अनड्वाहम् ९. ५, २९; १२. २, ४८.
अनड्वाहौ १४. १, १०.
अनड्वाहौऽइव ३. ११, ५; ७. ५५, ५.
अनत् ९. १५, ८.

अनति ४. ४, ३; ७. २६, २.
अनति १०. ८, १९; ११. ६, १४[2].
अनतिऽउद्यम् १०. ७, २८.
अनतिऽव्याध्यम् ९. २, १६.
अनतिऽसृष्टः १६. १२, ८; ११.
अनदत ३. १३, १.
अनदन्तः ६. ५०, २.
अननुऽकृत्यम् २०. १६, १०.
अननुऽदः २०. २१, ८.
अननुऽदिष्टः २०. ९६, ४.
अनन्तम् ८. ४, १७; १०. ८, १२[2]; २०. १२३, २.
अनपऽच्युतः २०. ४७, ३; १३७, १४.
अनपऽत्यताम् ४. १७, ६.
अनपत्यम् १२. ४, २५.
अनपत्यऽवन्तः १८. २, ४७.
अनपऽवाचना ८. ८, ९.
अनपऽस्पृक् १३. १, २७.
अनपऽस्फुरः २०. ९२, ७.
अनपऽस्फुरन् १०. १०, २७.
अनपऽस्फुरन्तम् १८. ४, ३६.
अनपऽस्फुरन्ती १२. १, ४५.
अनपऽस्फुरन्तीः १८. ४, ३४.
अनपऽस्फुरन्तौ ९. १, ७.
अनभिऽआरूढम् ११. ७, २३.
अनभ्रयः १९. २, ३.
अनमन् ४. ३९, १; ३; ५; ७.
अनमित्रम् ६. ४०, ३[4]; १२. १, ४७.
अनमित्राम् १२. १, १०.
अनमीवः २. २९, ६.
अनमीवम् १८. २, १२.
अनमीवा ११. १, २२.
अनमीवाः २. ३०, ३; ३. १४, ३; १२. १, ६२; २, ३१; १८. १, ४२; ३, ५७; ४, ४६.
अनमीवान् १२. २, २६.
अनयन् ७. १, १.
अनयन् २०. ६३, ३; १२४, ६.
अनयम् १८. ३, ३.
अनया ४. १८, ५; ६. १३३, ३; १०. १, ४; ५, १९; १६; १७; १८; १९; २०; २१; ११. १२, १२; २१.
अनयीत् १०. ४, २६.
अनर्तिषुः ६. ४९, ३.
अनर्पणम् १२. ४, ३३.
अनर्मणाम् ७. ८, १.
अनर्वम् ९. १४, २; १३. ३, १८.
अनर्शऽरातिम् २०. ५८, २.
अनवऽग्लायता ४. ४, ७; ६. १०१, ३.
अनवद्यऽरूपाः २०. १६, ३.
अनवद्याभिः २. २, ३.
अनवद्यैः २०. ४०, २; ७०, ४.
अनवऽद्राणः ८. १, १३.
अनवऽधर्ष्यम् ८. २, १०.
अनवऽब्रवः ४. ३१, ५.
अनवायम् ८. ४, २.
अनश्नन् ९. १४, २०.
अनश्रवः १२. २, ३१; १८. ३, ५७.
अनष्टऽपशुः १८. २, ५४.
अनसः १२. १, ४७; १४. १, ४१.
अनस्था ९. १४, ४.
अनस्थाः ४. ३४, २.
अनस्वतीऽइव १०. १, १५.
अनह्यन्त १९. २०, ३.
अना २०. ११४, १.
अनागःऽहत्या १०. १, २९.

अनागमिष्यतः १६. ६, १०.
अनागसः ७. ७, १; ३५, १; ८८, ३; ९. ५, २; १६. ६, १; १८. ४, ६९.
अनागसः १०. १, ७; १९. ५०, ७.
अनागसम् १९. ४४, ३.
अनागसम् २. १०, १; २; ३; ४; ५; ६; ७; ८; १०. १, १८.
अनागाः ६. २७, २.
अनागान् १८. १, ३६.
अनाजानन् ६. ११९, ३.
अनातुरान् १२. २, ४९.
अनाथम् १८. १, १२.
अनादिष्टाम् १५. ६, १६.
अनाद्यम् ८. २, १९.
अनाद्या ५. १८, ३.
अनाद्याम् ५. १८, १.
अनाधृषः ६. २१, ३.
अनाधृष्यः ७. ८९, १.
अनाधृष्या २०. ९४, ५.
अनाधृष्याः १६. २, १६.
अनापिः २०. ११४, १.
अनाप्ताः ४. ७, ७; ५. ६, २.
अनाबयो इति ६. १६, १.
अनामगः १९. ४५, २.
अनामनात् १२. ४, ५; ८.
अनामयाः ९. १३, १३; १४; १५; १६; १७; १८.
अनामयितुऽभ्याम् ४. १३, ७.
अनायतनः ११. ४, १८.
अनारम्भणे ८. ४, ३.
अनार्षेयाणाम् ११. १, ३३.
अनावन् २०. १६, १.
अनावयाः ७. ९५, ३.
अनावृत्ताम् १५. ६, १९.
अनाव्याधाम् १४. १, ६४.
अनाव्रस्कः १२. ४, ४७.
अनाशयः २०. २९, ५.
अनाशवः २०. ११६, २.
अनाशस्ताःऽइव २०. ७४, १.
अनास्माकः १९. ५७, ५.
अनास्माकम् १९. ५७, ४.
अनास्रावम् २. ३, २.
अनिऽओकाः १२. २, ४.
अनिःऽआहितः १२. २, ३५; ३६.
अनिःऽस्तृतः २०. ५३, ३; ५७, १३.
अनिजम् १०. ४, १९.
अनिध्मः १४. १, ३७.
अनिन्दाः ११. १०, २२.
अनिऽपद्यमानम् ९. १५, ११.
अनिऽभृष्टः १९. ६०, २.
अनिऽमानः २०. ३६, ७.
अनिऽमिषः १९. १३, २.
अनिऽमिषेण १९. १३, ३.
अनिऽमेषम् ९. १४, २२.
अनिऽस्तृतः ७. ८७, ३.
अनिऽहत्य १२. ३, ४४.
अनीकम् ४. २७, ७; ६. १२५, ३; ७. ३७, १; १३. २, ३४; ३५; २०. १७, ४; १०७, १३; १४.
अनीकऽशः ५. २१, ८; ९; ६. १०३, ३.
अनीनशः ९. १३, २२.
अनीनशत् १. २४; २.
अनीनशत् २. ३, ३; ५; ३. ७, १; ७. ५८, १; ८. ६, ६; ८; १९. ३६, १; ३; २०. ९६, १२.
अनीनशन् ८. ७, ३; १२. २, १४.

अनीनशम् **१.** २३, ४; **७.** १२०, ४; **९.** १३, २१.

अनीश्वराः **१२.** ३; ४२.

अनु **१.** २२, १; ३५, ४; **२.** ५, ५; १२, ५[२]; १३, ५; २७, २; ३४, ३; **३.** ७, २; ८, ६; ९, ६; १३, २; १७, ५; १८, ६; २१, ७; २३, ३; **४.** ८, १; १५, ४; ७; ८; ९; १२; २१, ४; ३८, ५; **५.** १, ३; २, १; ८, ९; १४, १; १७, ५; २१, १०; २७, ७; २८, ११; २९, ११; ३०, १; ६; १७; **६.** ११, २; १७, १; २; ३; ४; २६, २[२]; २९, ३; ३९, १; ४८, १; २; ३; ५३, १; ३; ६९, २; ७२, १; ७३, ३; ८९, २; ९०, २; ९४, २; ९७, ३[२]; १०५, १; २; ३; ११२, १; ११३, २[२]; ११८, १; २; १२१, ४; १२२, १; २; १३०, १; २; ३; ४; १३१, १; २[२]; १३४, ३[२]; **७.** १०, २; १७, १; २१, १; २; ३; ६; २२, १; २८, १; ३६, १; ४४, १; ५९, १; ६१, १; ६२, ७; ८७, ४[५]; १०२, ४; १२३, १[२]; **८.** १, ७; १०; १५; २, २१; ३, १८; ९, ८; १२; १३[२]; १५[२]; १६; १७; २३; **९.** १, १९; २४[३]; ४, २०; २४; ५, २; ४; १४, ९; **१०.** १, १९; २, १६[२]; १९; २२; २३; ४, ६; २६; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ३७; ४५; ५०; १०, ७[२]; **११.** १, ३१; ३६; २, १०; ६, १०; २४; २५; ७, २; १२; १०, ११; १९; २०; २१; २२; २४; २७; ११, ४; २१; १२, १; **१२.** १, १७; ५१; २, २१; ४३; ४९; ३, १७; ४, १; **१३.** १, ४; ७; १०; २, १४; १८; २१; ४०; ३, १; ११; २०; ६, ५; **१४.** १, १५; ४६; ५६; ६०; २, १०; ७४; **१५.** २, १; ९; १५; २१; ४, ३; ६; ९; १२; १५; १८; ५, २; ५; ७; ९; ११; १३; १५; ६, १; ४; ७; १०; १३; १६; १९; २२[२]; २४; ९, १; १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३; **१७.** १, १६[२]; **१८.** १, २०; २७[५]; ३२; ५०; २, ९; १३; ३, ४०[२]; ६९; ४, ३; २६; २८[४]; ४३; ७५; ७६; ८६; ८७; **१९.** ४, ४; ६, २; १३, ६[२]; १५, २; ४; २६, ३; ४९, २; ६; ५८, ३[२]; **२०.** ४, २; ११, ८; १५, २; ५; १६, १२; १७, ५; २६, ३; ३५, १५; ४०, ३; ४२, २; ४७, १५; १८; ६१, ३; ६७, ३; ६९, १२; ७०, १; ७६, २; ८१, १; ९१, ९; ९२, १५[२]; २०; ९९, २; १०५, २; १०६, ३; १०७, ४; १०९, १; २; ३; ११६, २; ११८, १; १३७, १०; १३९, २; १४३, ८.

अनुऽअर्चरन् १२, १, ८.

अनुऽअर्तप्यन्त **२.** ३५, १.

अनुऽअर्तिता **५.** १७, २.

अनुऽअविन्दत् **१९.** २७, ९; **२०.** ३४, ११.

अनुऽअविन्दन् **४.** २३, ६; ३५, २;

अनुऽआगन्ता **६.** १२३, १; २.

अनुऽआर्ततान **१८.** २, ३२.

अनुऽआनशे **४.** २५, २.

अनुऽआक्रयम् **२.** ३१, ४.

अनुऽआरभध्वम् **१२.** २, ४७; ४८.

अनुऽआरभेथाम् **६.** १२२, ३; **१२.** ३, २०; ४७.

अनुऽआरोहामि **६.** १२२, ४.

अनुऽआवर्ते **१०.** ५, ३७.

अनुऽआशये १०. ७, ९.
अनुऽइच्छन् ६. ३७, १.
अनुऽऐक्षन्त २. ३४, ३.
अनुऽऐच्छत् १२. १, ६०.
अनुऽकरेणं १२ २, २.
अनुऽकिरामि १८. ३, ६९; ४, २६; ४३.
अनुकूलम्ऽइव ५. १४, १३.
अनुऽक्षरन्ति २०. ९२, ९.
अनुऽगच्छन्ती १२. ७, १६.
अनुऽगत्य १९. ४४, १०.
अनुग्रासः २०. ११६, २.
अनुऽचक्रदे २०. ९, ४; ४९, ७.
अनुऽजहिरे १८. ३, ४६.
अनुऽजिघ्रम् ८. ६, ६.
अनुऽतन्वन्ति ९. १३, १४.
अनुऽतप्यमानम् २. ३५, २.
अनुऽतिष्ठते ९. ११, ६.
अनुऽतिष्ठन्ति ११. १२, २७; १९. ४८, ५.
अनुत्ऽमदितः ६. १११, १; २; ३; ४.
अनुदः ७. ८९, २.
अनुऽददाति २०. ३४, १०.
अनुऽदहन् २. २५, ४.
अनुदिताम् ५. १, २.
अनुऽदेयी १४. १, ७.
अनुऽध्याः ७. ११९, २.
अनुऽनिक्षन्ति ९. १३, १५.
अनुऽनिर्दह ९. २, ९.
अनुपऽक्षितौ ६. ७८, २.
अनुपऽदस्वतः ४. ११, ९; १२.
अनुपऽदस्वतीम् २. ३६, ५; ७. ८५, २.
अनुऽपरियन्ति १५. १७, ८.
अनुपऽसेचनः ११. ३, २४.
अनुऽपस्पशानः ६. २८, ३.
अनुऽपस्पशानम् १८. १, ४९.
अनुऽपालयन्ती १८. ३, १.
अनुऽपूर्वम् १२. २, २४; २५; २०. १२५, २.
अनुपूर्वऽवत्साम् ९. ५, २९.
अनुऽप्रयानम् ७. ७७, ६.
अनुऽप्रयुङ्क्ताम् १२. १, ४०.
अनुऽप्रयुङ्क्ते ११. २, १३.
अनुऽप्रवोढुम् १९. ५९, ३.
अनुऽप्राविशथाः १०. १०, २२.
अनुऽप्रेमः ५. ७, ३.
अनुऽप्रेयतुः १९. ४४, १०.
अनुऽबध्नन्ति ५. १९, १२.
अनुऽबुद्धम् ४. २४, ६; १०. १, १९.
अनुऽमतम् ६. ७१, २; ७. २१, ४.
अनुऽमता ३. १७, ९.
अनुमतिः १. १८, २; ६. ११, ३; ७. २१, १; ५; ६; २५, १.
अनुऽमतिम् ५. ७, ४.
अनुऽमते ६. १३१, २; ७. २१, ४; ६.
अनुऽमते २. २६, २; ७. २१, २.
अनुऽमत्याः ९. ४, १२.
अनुऽमदन्ति ५. २, ४; २०. १०७, ७.
अनुऽमन्यमानः ७. २१, ३.
अनुऽमन्यमानौ १४. २, ४२.
अनुऽमाद्यां १४. १, ४७.
अनुऽमेयाः ६. १३७, २.
अनुऽमृश्य २०. १६, ५.
अनुऽम्रोक २. २४, ३.
अनुऽयाजाः १. ३०, ४.
अनुऽराधम् १९. १५, २.
अनुऽराधा १९. ७, ३.
अनुऽरोधनम् ६. १०२, ३.
अनुऽवपते १२. २, ५०.

अनुऽवर्तते **१२.** २, ३७.
अनुऽवर्तयन् **११.** १२, १८.
अनुऽवर्त्मानः **३.** ८, ६; **६.** ९४, २.
अनुऽवाकैः **१९.** २२, १.
अनुऽविक्रमते **९.** ७, १२.
अनुऽविद्यते **१९.** ५०, ४.
अनुऽविद्वान् **१२.** २, ३८; ५२.
अनुऽविसिच्यते **८.** १९, ४.
अनुऽवृजौ **९.** ४, १२.
अनुऽव्रतः **३.** ३०, २.
अनुऽव्रता **३.** २५, ४; **१३.** १, २२; **१४.** १, ४२.
अनुऽव्यचलत् **१५.** १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३.
अनुऽव्यचलन् **१५.** २, २; १०; १६; २२; ६, २; ५; ८; ११; १४; १७; २०; २५; ९, २.
अनुऽव्यवर्तयन्त **१५.** ७, २.
अनुऽशिष्टाः **१९.** ५६, ४.
अनुऽशेरते **८.** ६, १९.
अनुष्ठु **१२.** ४, ४५.
अनुऽसंक्राम **१८.** २, ५७.
अनुऽसंचरन्ति **३.** २१, ७; **४.** ३८, ५.
अनुऽसंचरन्ती **१८.** ३, ४.
अनुऽसंदह **१२.** ११, २.
अनुऽसंदिशामि **४.** १६, ९.
अनुऽसंप्रयाहि **११.** १, ३६.
अनुऽसंयन्ति **११.** ७, २.
अनुऽसंरभेथाम् **६.** १२२, ३.
अनुऽसंवहन्ति **१०.** ८, ८.
अनुऽसंविदुः **१०.** ७, १७; २६.
अनुऽसंविशस्व **१८.** ३, ९.
अनुऽसर्प **२.** २४, ४.
अनुऽसर्पति **९.** १३, ७.

अनुऽसर्पन्ति **९.** १३, १७.
अनुऽसूर्यम् **१९.** ४९, ५.
अनुऽस्तुप् **८.** ९, २०; **१९.** २१, १.
अनुऽस्तुभम् **८.** ९, १४.
अनुऽस्थाता **१५.** ५, २; ५; ७; ९; ११; १३; १५.
अनुऽस्थातारम् **१५.** ५, १; ४; ६; ८; १०; १२; १४.
अनुऽस्थातारौ **१५.** ४, २; ५; ८; ११; १४; १७.
अनुऽस्पष्टः **२०.** ९६, ४.
अनुऽस्फुरम् **१.** २, ३.
अनुऽस्वधम् **२०.** १३, ४.
अनुऽहवम् **१९.** ८, ४.
अनुऽहार्य **५.** १८, ९.
अनुऽहूतः **५.** ३०, ७.
अनूकम् **४.** १४, ८.
अनूकात् **९.** १३, २१.
अनूक्यम् **९.** ६, १.
अनूक्यात् **२.** ३३, २; **२०.** ९६, १८.
अनूक्ये इति **११.** ३, ९.
अनूचः **३.** १, ४.
अनूची **१०.** १०, १०.
अनूच्ये इति **१५.** ३, ५.
अनूनः **७.** ८६, ३.
अनूनम् **७.** ८६, ३; **१२.** ३, ४८.
अनूप्याः **१.** ६, ४; **१९.** २, २.
अनूर्मिम् **२०.** ६६, १.
अनूषत **२०.** १४२, ४.
अनूषत **२.** १, १; **२०.** १७, १; ३८, ४; ४७, ४; ७०, २; ७; ९२, ८; १०४, १; ११९, १.
अनृक्षरा **१८.** २, १९.

अनृक्षराः **१४.** १, ३४.

अनृणः **६.** ११७, १; २.

अनृणाः **६.** ११७, ३^{४}.

अनृतऽदेवः **८.** ४, १४.

अनृतम् **१.** १०, ३; **२.** १९, ५; **४.** ९, ७; १६, ६; **६.** ६१, २; ३; **७.** ९४, ३; **९.** १५, २३; **१०.** २, १४; ५, २२; **१२.** ३, ५२; **१८.** १, ४; **१९.** ४४, ८.

अनृतऽवाक् **४.** १६, ७.

अनृतस्य **२०.** ९१, ४.

अनृतेन **६.** ७१, ३; **७.** ७३, २; **८.** ३, ११.

अनृतेभिः **८.** ४, ८.

अनृत्यत् **१०.** १०, १४.

अनेन **१.** १६, ३; **३.** १९, २; **५.** २८, २; **६.** ६५, २; **८.** ५, ३^{४}; **१०.** ५, १५^{२}; १६^{२}; १७^{२}; १८^{२}; १९^{२}; २०^{२}; २१^{२}; **१८.** ४, ५०.

अनेव **१६.** ७, ४.

अनेषत **६.** २८, २.

अनेहसम् **७.** ७, १; **२०.** ९२, १३.

अनेहा **६.** ८४, ३.

अनैक्षीत् **२.** ७, १.

अनोनवुः **२०.** ९२, १९^{२}.

अन्तः **९.** १५, १४.

अन्तः **१.** २, ४^{२}; ४, ४; ६, २; १३, ३; ३०, ३; **२.** १०, ५; ३१, ५; ३२, १; **३.** ६, ३; १०, ४; २०, ८; २१, १; २^{२}; ७^{२}; २२, ३; **४.** ८, ७; १०, ७; ११, ३; २६, ५; २८, ५; ३०, ७; **५.** ११, ८; ९; ३०, १६; **६.** १, २; ३१, २; ५३, २; ७३, २; ८०, ३; ८७, १; १३२, १; २; ३; ४; ५; **७.** ३७, १; ४४, १; ९२, १; **८.** १, ११; ४, ३; ५, ६; ९, ११; **९.** ३, ६; १४; २२; १३, ७; ९; १४, ९; १५, १०; ११; १२; **१०.** २, ७; ५, १५; १६; १७; १८; १९; २०; २१; ७, १०; ८, १३; २८; १०, २५; २८; **११.** २, ११; २४; ६, २०; ७, ३; ९, १; ६; १०, २; ६; १२, ४; **१२.** १, १९; ३७; ६०; २, ३३; **१३.** १, १; २; ४०; ५९; २, ३०; ३, १५; २०; **१४.** १, ३७; **१७.** १, ८; १३; २९; **१८.** ४, ८९; **१९.** ३, २; २७, १०; ४८, १; ७२, १; **२०.** ३४, ३; ४८, ५; ५६, ६; ८९, ८; ९६, १४; १२६, १५.

अन्तःकोशम्ऽइव **१.** १४, ४.

अन्तःऽदधानाः **५.** २८, ८.

अन्तःऽदावे **६.** ३२, १.

अन्तःऽदेशाः **८.** ८, २२; **१०.** ६, १९.

अन्तःऽदेशात् **१५.** ५, १; २; ४; ५; ६; ७; ८; १०; ११; १२; १३.

अन्तःऽदेशान् **१५.** ६, २४; १४, २३.

अन्तःऽदेशेभ्यः **४.** ४०, ८; **५.** १०, ७; **१५.** ५, १४; १५.

अन्तःऽधिः **१२.** २, ४४.

अन्तःऽपात्रे **११.** ११, १५.

अन्तःऽवान् **९.** ४, ३.

अन्तःऽहस्तम् **७.** ५२, २.

अन्तःऽहितम् **१९.** ४२, १.

अन्तःऽहिताः **११.** ११, १६.

अन्तकः **६.** ४६, २; **८.** १३, ७; **१६.** ५, २; ४; ५; ६; ७; ९; **१९.** ९, ७.

अन्तकाय **८.** १, १.

अन्ततः **१४.** १, ६४.

अन्तम् **९.** १५, १३; **१०.** ७, ४२; **१२.** ३, ३४; **१५.** ७, १.

अन्तमः **२०.** ८३, २.

अन्तमानाम् **२०.** ५७, ३; ६८, ३.

अन्तरम् **१.** १९, ४; **२.** ३०, ४[२]; **७.** १०५, १.

अन्तरा **३.** १५, २; **४.** १६, ५; **५.** २०, ७; **६.** ५५, १; **७.** ११४, ३; **८.** ६, ३; **९.** ३, १५; १३, ९; **१०.** ७, २८; ८, ३९; **११.** ६, १४; ७, ११; १०, ३४[२]; **१२.** २, ४४; **१३.** १, ५७; ५८; ३, ६; **१४.** २, ३४; **१९.** ५६, ४; **२०.** ६, ९; ९६, १४; १२६, १६; १७.

अन्तरिक्ष **६.** १३०, ४.

अन्तरिक्षम् **२.** १२, १[२]; **३.** २१, ७; २९, ८; **४.** २, ४; ११, १; १४, ३; २०, १; ३५, ३; ३९, ४; **५.** ३, ३; ९, ७; २८, २; **६.** ४०, १; १२०, १; २; **७.** १, २; ६, १; ७, २; **८.** १, १२; ४, २३; ८, ५; २१; २२; **९.** १, २१; ३, १५; ५, २०; १२, ५; १५, २४; **१०.** २, २४; २५; ५, २६; ७, ३; १२; ३२; ३५; ८, ३६; ९, १०; **११.** २, १०; २७; ७, ४; ८, ६; ११, ४; **१२.** १, २०; ५३; ३, २०; २६; **१३.** १, ७; ९; १६; ३३; २, ३२; ३५; ४५; ७, ३; **१४.** २, ६९, **१५.** १७, २; **१७.** १, १३; **१८.** २, ९; ४९; ३, ५९; ४, ५; ६; **१९.** ६, ८; ९, १; १४; १०, ५; १५, ५; ३२, ९; ५८, २; **२०.** ११, १०; २८, १; ३४, २; ३९, २; ८७, ३; ९३, ६; १०७, १४; १४३, ८.

अन्तरिक्षऽवन्तम् **१९.** १८, २.

अन्तरिक्षऽसंशितः **१०.** ५, २६.

अन्तरिक्षसत्ऽभ्यः **१८.** ४, ७९.

अन्तरिक्षऽसदः **१०.** ९, १२; **११.** ८, १२.

अन्तरिक्षस्य **५.** २४, ८.

अन्तरिक्षा **२०.** ३६, ८.

अन्तरिक्षाणि **१९.** २७, ३, **२०.** ९४, ८.

अन्तरिक्षात् **४.** १०, १; १४, ३; ४०, ६; **५.** १०, ८; **६.** १२४, १; २; **७.** २७, ८; **९.** १, १; **१०.** १, १३; ५, २६; **१२.** ११, ११; **१३.** ७, ३; **१६.** ४, ४; ७, ६; **१८.** ४, ९; **१९.** ३, १; ३५, ४; **२०.** १६, ५; ३५, ९.

अन्तरिक्षाय **५.** ९, ३; ४; **६.** १०, २; **७.** १०७, १; **११.** २, ४.

अन्तरिक्षे **१.** ३०, ३; ३२, २; ३३, ३; **२.** १०, ३; **४.** ८, ५; १४, ८; २५, २; ३९, ३[२]; **७.** ६८, १; १०२, ८; **८.** ३, ३; ५; ११, १; **९.** ४, १०; ११, ८[२]; **११.** २, २३; १२, २; ८; **१३.** २, ३०; ३, २२; **१५.** १३, ४; **१७.** १,१२; **१८.** ३, ६३; **१९.** ८, १; १७, १२; **२०.** १३९, २.

अन्तरिक्षेण **४.** २०, ९; ३८, ५; ६; ७; **६.** ८०, १; **११.** ४, ८; **१३.** ३, १३; **१९.** १७, २; १९, २.

अन्तऽवत् **१०.** ८, १२.

अन्ताः **१.** १७, ३; **१४.** २, ५१.

अन्तात् **१८.** ३, ६५.

अन्तान् **१४.** १, ४५; **२०.** ८८, १.

अन्ति **१०.** ४, ९; ८, ३२[२]; **१८.** ३, २३.

अन्तिकम् **३.** ११, २; **२०.** ९६, ७.

अन्तिकात् **१२.** २, ३८; ५०; ५२.

अन्तिकात्ऽइव **४.** १६, १.

अन्तितम् **६.** ४, २; **८.** ५, ११.

अन्तिसुम्ने इत्यन्तिऽसुम्ने **७.** ११७, १; **१४.** २, ४५.

अन्तै २०. ७७, २.
अन्तौ ६. ८९, ३; १३. २, ६; १३.
अन्धः ७. ६०, २; २०. ७७, १.
अन्धः ६. १२९, ३; ९. १४, १५; ११. ४, ३.
अन्धम् ९. १३, ४.
अन्धसः ६. २, २; २०. १, १; ४, १; ५, २; ६, १; ९, १; १३, २; २३, ६; ३१, ४; ४९, ४; ५३, १; ५७, ११; ६४, ४; ७१, ७; १२४, २.
अन्धा ९. २, १०; २०. ७७, ४.
अन्धेन १८, ३, ३.
अन्नऽअदः १३. ३, ७.
अन्नऽअदम् १५. १४, १; ३; १३; १५; १७; १९; २१; २३.
अन्नऽअदाय १९. ५५, ५.
अन्नऽअदीः १५. १४, ५; ११.
अन्नऽअदीभिः १५. १४, ६; १२.
अन्नऽअदीम् १५. १४, ७; ९.
अन्नऽअदेन १५. १४, २; ४; १४; १६; १८; २०; २२; २४.
अन्नऽअद्यम् १२. ६, ४; १३. ५, १; ६, १; १५. ७, ४; ५; ८, २.
अन्नऽअद्यस्य १५. ८, ३.
अन्नऽअद्या १५. १४, ८; १०.
अन्नऽअद्येन १३. ८, ४; ५; ६; ९, १; २; ५.
अन्नऽतेजाः १०. ५, ३४.
अन्नऽपतये १९. ५५, ५.
अन्नऽपतिः १३. ३, ७.
अन्नऽभागः ३. ३०, ६.
अन्नऽभागम् १२. १, २९.
अन्नम् ३. २७, ३; ४. ३०, ४; ५. १८, ४; ७; ६. ६३, १; ७१, १; ३^{२}; ११६, १; ७. १०६, १; ८. २, १९; ७, १२; ९. ७, ७; ८; ९; १०. २, २७; ५, ४५; ८, २२; १०, ८; ११. ७, २५; १२. १, ३; ४; ४२; ६, ४; १३. ५, १; ६, १; १५. ७, ४; ५; ८, २; १४, २; ४; ६; ८; १०; १२; १४; १६; १८; २०; २२; २४; १९. ७, ४; २०. ८७, २.
अन्नम्ऽअन्नम् १०. ६, ५; ३३.
अन्नऽवान् १८. ४. २१.
अन्नऽविदः ६. ११६, १.
अन्नस्य ५. २८, ३; ७. ६२, ५; १५. ८, ३; १९. ३१, ८.
अन्ना २०. ३५, ७.
अन्नानाम् १८. ४, ५४.
अन्नानि १९. ३१, ४.
अन्नाय १२. ३, ५७.
अन्ने १०. ५, ४४; १२. १, ४; २०. ७६, ४.
अन्नेन १०. ६, २३; १२. १, २२.
अन्नैः २०. ७६, ३; ५.
अन्यः २. ४, ५^{२}; ३. २, ६; ३०, १; ५; ४. १३, २^{२}; ५. ११, ४; ७. ८४, ४; ८५, ३; ८६, १^{२}; ८. ९, १९; ९. १४, २०^{२}; १५, २६; १०. ८, २३; ११. ६, २६; ७, १०^{२}; ११^{२}; १२. ३, ५०; १३. १, ५०^{२}; २, ११; १४. १, २३^{२}; १८. १, १६; १९. ३५, ५; २०. १५, ४; १७, ५; १२१, २.
अन्यकेषाम् २०. ९५, २; ३; ४.
अन्यऽक्षेत्राणि ५. २२, ८.
अन्यऽक्षेत्रे ३. ३, ४; ५. २२, ९.
अन्यत् ५. ११, ५; ६; ६. १२, १; १०. २, २२; २३; ७, ३१; ११. १०, २३; १३. २, ४३^{२}; १८. २, ३१; ५१; १९. ५३,

४; **२०.** १८, २; ८२, २; ८५, १; १२३, २[२].

अन्यतः **१३.** ३, १२[२]; **२०.** ६८, ५.

अन्यत्र **३.** २३, १; **६.** ११, ३; २६, ३; ४०, २; ९३, २; १४०, ३; **७.** ११६, १; १२०, २; **९.** २, २५; **१०.** १, १६; **११.** २, १९; २१; २६; **२०.** १२६, २.

अन्यऽनाभिः **१.** ३०, १.

अन्यम् **३.** २, ६; ३०, १; **४.** १८, ३; **६.** २०, १; २६, २; **९.** ५, २७; १५, १६[२]; **१२.** ३, ५०; **१३.** २, ११; **१८.** १, ११; १६; ४०.

अन्यया **११.** ४, ५; १८.

अन्यऽवर्णाम् **१२.** ३, ५४.

अन्यस्मिन् **८.** ९, १९; **१२.** ४, १५.

अन्यस्मै **३.** ३०, ५; **१२.** ३, ४६.

अन्यस्य **१०.** ८, २३.

अन्यस्याम् **१.** ३२, ४[२].

अन्या **६.** ३०, २; **१०.** ७, ४२[२]; **१८.** १, १५.

अन्याः **६.** ६०, २; **१०.** ८, ३.

अन्यान् **१.** १०, २; ३०, ३; **२.** २९, ३; **४.** ५, ७; ३६, ३; **७.** ३६, १; **१२.** १, ५८; **१९.** ३३, ५; ५०, ६.

अन्याभ्याम् **११.** ४, २; ३; १३; १४; १५; १६; १७.

अन्याम् **१.** ३२, ४; **१२.** ४, १३.

अन्याम्ऽअन्याम् **२०.** ७५, ३.

अन्यासाम् **६.** ६०, २; **७.** ३८, १; ३९, ४.

अन्ये **२.** ६, २; २८, १; **३.** ११, ५; ७; **९.** १४, १२; **१२.** ३, ४२; ५१; ४, २२; **२०.** ९६, १; १४३, ५.

अन्येद्युः **१.** २५, ४; **७.** १२१, २.

अन्येन **११.** ४, १; ४; ८; ९; १०; ११; १२; **१८.** १, ९; १३; **१९.** ६, ४.

अन्येभिः **८.** ५, ९.

अन्येभ्यः **१२.** २, १६.

अन्येभ्यः **१२.** ४, २३.

अन्येषाम् **१२.** २, ५१; **१४.** २, ८.

अन्येषु **११.** ६, २३.

अन्येषु **२०.** ४५, ३.

अन्यैः **११.** ४, ६; ७.

अन्वञ्चम् **६.** १३४, ३.

अप **१.** २, २; १०, ४; १८, ३; २१, ४[२]; २८, १; **२.** ३, ६; ८, २[३]; ३; ४; ५; ३५, २; **३.** ७, ७[२]; ९, १; ११, ६; १२, ६; २३, १; **४.** ३, ५; ८, २; १४, ४; १७, ६; ७; १८, ७[३]; ८[२]; २०, ५; २५, ४[२]; ३१, ७; ३२, ५; ३३, १[२]; २; ३; ४; ५; ६; ७; ८; ३५, ७; ३७, १२; **५.** ३, १०; ६, ७; ७, ७; १९, ९; २२, १[२]; **६.** ४, २; ६, २; ३; १४, ३; १६, ३; २०, १; ४५, १; २; ७३, ३; ८१, १; ८३, १; २; ८७, २; ९१, १; ११९, ३; १२६, १; २; १२९, १; २; ३; १३४, १; **७.** ६७, २; ३; ८९, २; ९३, १; **८.** १, २१[३]; २, ११; १२; ४, १७; २३; ६, ४; ५; ७, १४; ८, ५; ११; **९.** २, २५; ५, ७; ११; **१०.** १, १; २; १०; १३; १४; ५, २३; ७, ४०; ४२; **११.** १, २९; ३, ४; ६, १४; ७, १९; **१२.** १, ३७; ४९; २, ४७; ३, १४; १९; ४३; ४९; ५४; ५, ६; ६, ५; **१३.** २, ९; १५; १७; **१४.** १, ३८; ५९; २, ६; ११; ४८; ६८[२]; ६९; **१६.** १, १०; ६, २; **१८.** १, २५; ५५; २, २७; ३३; ४०; ५७; ३, २१; ७३; ४, ४९; **१९.** १२, १;

२०, १; ३४, ३; ३६, ४; ४९, १०[३]; ५०, ५; ५६, ६; २०. १६, ५; १७, २; २०, ५; ४३, १; ४७, १४; ५७, ८; ७०, १२; ७८, ३; ८९, ७; ९१, ११; ९६, २४[२]; १२५, १[४]; १३७, ७.

अपऽअकषन् १०. ७, २०.

अपऽअतक्षन् १०. ७, २०.

अपऽअयातै ७. ९५, ३.

अपऽआवृत्य १२. २, ३४.

अपऽईक्षमाणा १२. ७, ८.

अपऽउदकः ५. १६, ११.

अपऽउदकम् ५. १३, २.

अपऽउदकस्य ५. १३, ६.

अपऽउदित ६. ५०, २.

अपऽऊर्णुवन् ९. ३, १८.

अपऽऋतुः ३. २८, १.

अपः ७. ५०, १; १८. १, ३१.

अपः १. ४, ३; ५, ४; २. ३, ६; ५, ५; ४. १५, १२[२]; २१, ७; २७, ४; ६. २२, १; २; २३, १; ३; ७. ४२, १; ७९, १; ९४, १; ११४, २; ८. ९, २३; ११, ८; १०; ९. ६, ४; १५, २२; १०. २, ७; ५, ३३; ४६; ९, २७; १०, ८; ११. १, १५; १८; ७, ७; ८, ११; १०, २८; १३. १, २; २१; ३, ९; १४. १, ३७; २, ६९; १५. ४, ५; ११, ४; १८. २, ७; १९. २, ५[३]; १८, ६; २०. ९, ४; ११, ८; १५, ६; १७, ८; ३६, ८; ४९, ७; ६१, ३; ५; ६२, ९; ६३, ९; ७५, २[२]; ७७, ६; ७; ८; ७९, २; ९०, ३.

अपऽकामम् ३. १३, ३.

अपऽकामस्य २. १२, ५.

अपऽकामात् ९. १३, ८.

अपऽक्रामन् ७. ११०, १.

अपऽक्रीताः ८. ७, ११.

अपक्षाः ११. ७, २१.

अपऽगाः १. ३४, ५; २. ३०, १; ६. ८, १; २; ३.

अपऽगूहमानः १९. ५६, २.

अपचत् ४. ३५, १.

अपचन्त ९ १५, २५.

अपऽचित् ६. ८३, ३.

अपऽचितः ६ ८३, १.

अपऽचितः ७. ८०, २[२].

अपऽचिताम् ७. ७८, १.

अपचिताम्ऽइव ६. २५, १; २; ३.

अपतत् ५. २८, ६.

अपतिः ८. ६, १६.

अपतिऽघ्नी १४. २, १७; १८.

अपतिऽघ्नीम् १४. १, ६२.

अपत्यम् ७. ११३, १.

अपत्यऽवत् १२. ४, १.

अपथम् ६. ७३, ३; १०. १, १६.

अपथेन ५. ३१, १०.

अपदम् ६. २९, २.

अपद्यन्त १४. २, ३२.

अपऽधा २०. ३४, ३.

अपऽध्वंसेन ४. ३, ५.

अपऽनीता ५. १७, ६.

अपऽपद्यते ४. २८, ५.

अपऽपापम् १९. ८, ५.

अपपुषः ६. १३९, ४.

अपप्तत् ७. १०१, १.

अपप्तत् ५. ३०, ९; ६. १२४, १.

अपृक्थाः ७. ९३, १.

अपऽबाधमानः १२. ३, १५; १९. १३, ८.

अपऽब्रवत् ६. ५७, १.
अपऽभर्तवै १८. १, ५०.
अपऽभूतये ५. ८, ५.
अपऽमयाः १९. ५७, ५.
अपऽमा १०. ४, १.
अपऽमित्य ६. ११७, २.
अपऽमित्यम् ६. ११७, १.
अपऽमृज्य ४. १८, ८.
अपऽमृष्टम् ६. ११३, ३.
अपरऽअह्णः ९. १०, ५.
अपरः ९. ५, २८; १०. १, २७^{2}; ४, १; १२. २, २३; २५; १३. २, १४; १४. २, ३.
अपरम् ९. ५, २७; १३. १, ५६; ५७; १४. १, ६४; १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५; ५०; ५१^{2}; ४, ४४.
अपरम् २०. १२६, ११.
अपरस्याः २०. ७६, २.
अपराः १०. १०, ८.
अपराऽजितः ५. ३०, १७; ८. ५, २२; १०. ४, १९.
अपराऽजिताम् १०. २, ३३.
अपऽराद्धः ६. ११६, २.
अपरान् १०. ३, १३; १४; १५.
अपराऽपरणः १२. ९, ७.
अपराम् ६. १८, १.
अपरासः १८. १, ४६.
अपराऽहतः १८. ४, ३८.
अपरिऽपरेण १८. २, ४६.
अपरिऽमितः ९. ५, २१; १५. १५, ९.
अपरिऽमितम् ९. ५, २२^{2}.
अपरिऽमिताः १५. १३, ९; १०.
अपऽरुद्धम् ३. ३, ४.
अपऽरूपम् १२. ४, ९.
अपरे ९. ११, ३; १८. ३, ७२; २०. ९४, ७.
अपरेण १०. ४, ३.
अपलिताः १९. ६०, १.
अपऽलुप्यते ५. १७, ७.
अपऽवक्तारः ५. १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११.
अपऽवान् १८. ४, २४.
अपऽवान् १९. ५०, ४.
अपऽवासे ३. ७, ७^{2}.
अपऽवृतम् २०. १५, १.
अपऽव्रतेन ३. २, ६.
अपशुऽघ्नीम् १४. १, ६२.
अपऽशुष्यति ६. १३९, ४.
अपश्चा १९. ५५, ५.
अपश्यत् ४. १४, १; ९. १४, ९; १५, ३; १५. १, २; १९. ५६, २; २०. १६, ८.
अपश्यन् २०. ६३, ३; १२४, ६.
अपश्यम् ९. १५, ११; १८. ३, ३.
अपश्यम् ९. १४, १; १५, २५; २०. १३७, ८.
अपऽश्रयः १५. ३, ८.
अपऽश्रितम् २०. ४१, २.
अपऽश्रितौ ६. १२७, २.
अपसः ६. २३, १; १९. २, ३; २०. १८, २.
अपऽसिध्य ८. २, ७.
अपऽस्कम्भस्य ४. ६, ४.
अपस्पृधेथाम् ७. ४५, १.
अपऽस्फुरम् २०. ९२, ७.
अपस्युवः २०. ९३, ४.
अपाः २०. ३२, ३.
अपाक् २०. ९४, ७; १२०, १.
अपाक्तः ८. ४, १९.

अपा॑ङ् **९.** १५, १६.
अपा॑चः **२०.** १२५, १.
अ॒पा॒चीन॑म् **६.** ९१, १.
अपा॑चीम् **१८.** ३, ३; **२०.** ९१, ५.
अपा॑ञ्चः **५.** ३, २.
अपा॑ञ्चम् **३.** ३, ६.
अपा॑ञ्चौ **७.** ७३, ४.
अपा॑त् **२०.** ९२, ८^{२}.
अ॒पात् **९.** १५, २३; **१०.** ८, २१.
अ॒पा॒नः **२.** २८, ३; **५.** ३०, १५; **७.** ५५, ३; ४; **११.** ६, १३; **१२.** ६, ३; **१५.** १६, १; २; ३; ४; ५; ६; ७; **१६.** ४, ३; **१८.** २, २६; ४६; **१९.** ५१, १.
अ॒पा॒न॒तः **६.** ३१, २; **२०.** ४८, ५.
अ॒पा॒न॒ते **११.** ६, ८.
अ॒पा॒नम् **१०.** २, १३; **१९.** २७, ६.
अ॒पा॒नाः **६.** १०४, १; **८.** १, १; **११.** ३, २९; **१५.** १५, २.
अ॒पा॒नाय॑ **६.** ४१, २; **१९.** ४५, ६; ७; ८; ९; १०.
अ॒पा॒नेन॑ **१३.** ३, ४.
अपा॑म् **६.** ३, १; ३; **१४.** १, ३७.
अ॒पाम् **१.** ४, ४; ३५, ३; **४.** ४, ५; ८, ५; १५, २; ३; १०; १२; ३७, ३; **५.** ५, ७; १९, १३; १४; २४, ४; २८, ६; २९, ८; **६.** १०६, २; १२४, १; १२५, २; **७.** ४०, १; ५१, १; **८.** ७, ८; **९.** ४, २; ५; **१०.** ५, ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; ५०; ८, ३४; ३५; **११.** १, १३; ६, २६; **१५.** २, १८; **१६.** १, १; ६; **१८.** ३, ५; ५६; ६५; **१९.** २, ४^{३}; ११, ३; ३३, १; ४२, ४; ४५, ३; **२०.** २८, ४; २९, ३; ३४, ७; ३५, १२; ३९, ५; ४४, २.
अ॒पाम्ऽइ॑व **२०.** १५, १.
अपा॑मार्ग **४.** १७, ६; ७; १८, ८; **७.** ६७, १; २; ३.
अ॒पा॒मा॒र्गः **४.** १७, ८; १८, ७; १९, ४.
अ॒पा॒य॒य॒त् **१०.** १०, ९.
अ॒पा॒रेण॑ **२०.** ९४, १.
अ॒पा॒लाम् **१४.** १, ४१.
अ॒पा॒ष्ठऽव॑त् **१४.** १, २९.
अ॒पा॒ष्ठात् **४.** ६, ५.
अपि॑ **१.** ७, ७; १४, ४; २७, १; **२.** २, ३; ७, ५; ९, २; १०, ७; १२, ८; ३२, २; ३४, २; **३.** १३, ४; **४.** १२, ३; ३४, २; ३६, २; ३७, ७; **५.** २, ३; ८, ४; १३, ५; १८, १३; २३, ९; ३०, १५; **६.** ३२, २; ४५, ३; ५०, १^{२}; ५५, ३; ७७, २; **७.** २१, ३; ३६, २; ५१, १; ५९, २; ७३, ४; ५^{२}; ९५, १; ९७, १; १००, ३; **८.** ३, २; ३, १५; १२, २; **९.** ४, २; ५, १; १४; १४, ७; **१०.** १, २१; ३, ९; ४, २६; ५, २३; ६, १; ९, १; १०, ६; ३३; **११.** १, ३३; ९, ३; १२; **१२.** १, ४; २५; ३५; २, ४; ९; ४५; ५३; ३, २२; ४४; ५३; ४, ३१; ३८; ३९; ९, ६; १०, ५; **१३.** ५, ३; ४; ५; **१४.** २, २९; **१६.** ७, ३; १२; **१८.** १, ३३; ५८; २, ११; १४; १५; १६; १७; १८; **१९.** ३८, २; ४५, १; ५९, ३; **२०.** १८, ५; ५४, ३; ९४, ४; १०७, ६; १२५, ७; १२६, ४.
अपि॒ऽऊ॒हे **८.** ४, १४.
अपिं॑शत् **५.** १२, ९.
अ॒पिं॑शन् **२०.** १६, ११.

अपिऽत्वम् १०. ८, ५.
अपिऽधानम् ७. ३६, ३; ११. ३, ११; १८. ४, ५३.
अपिऽनद्धम् ९. ३, १८; २०. १६, ८.
अपिऽनह्यमाने १२. ७, १४.
अपिबः २०. १२५, ५.
अपिबत् २. ५, ७; २०. ९५, १.
अपिबन् १०. १०, ३०.
अपिऽशीर्णाः ४. ३, ६.
अपीच्यम् २०. ४१, ३.
अपीच्ये १८. १, ३६.
अपीपतत् ७. ६६, १.
अपीपदाम १०. ५, ४२.
अपीपरः १७. १, २५; २६.
अपीपरन् ८. १, १७.
अपीपरम् ८. १, १९; २, ९.
अपीपेम २०. ९७, १.
अपीषन् ४. ६, ७.
अपुः ९. १४, ५.
अपुनःऽदीयमाना १२. ९, ६.
अपुनरिर्ति २०. १६, १०.
अपूपऽअपिहितान् १८. ३, ६८; ४, २५.
अपूपऽनाभिम् १०. ९, ५.
अपूपऽवान् १८. ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.
अपूर्वेण १०. ८, ३३.
अपूर्व्य २०. १४, १; ६२, १.
अपृक्थाः ७. ९३, १.
अपृक्ष्महि ७. ९४, १; १०. ५, ४६.
अपृणत् २०. ११, १.
अपेचिरन् ५. १८, ११.
अपेशसे २०. २६, ६; ४७, १२; ६९, ११.
अप्नस्वती २०. ८९, ३.

अप्यम् २०. १२६, १२.
अप्या १८. १, ४; १९.
अप्याः १९. ११, २.
अप्रऽचङ्कशाः ८. ६, १६.
अप्रजसम् ७. ३६, ३; १२. ९, ७.
अप्रजस्ताम् ९. २, ३.
अप्रजाःऽत्वम् ८. ६, २६.
अप्रजाःऽत्वार्य १०. १, १७.
अप्रति ७. ५२, १[२]; ९८, १; ११५, १; २०. १२, ३; २१, ६.
अप्रतिऽइतः २०. ९०, ३.
अप्रतिऽइतौ ७. २६, १.
अप्रतिब्रुवत्ऽभिः ३. ८, ३.
अप्रतिऽमन्यूयमानाः १३. १, ३१.
अप्रतिऽमानम् २०. १३७, ११.
अप्रतिऽस्कुतः २०. ४१, १; ६३, ४; ७०, १२; १४.
अप्रतिऽस्कुतम् २०. ५५, १.
अप्रतिऽस्थानः ११. ४, १८.
अप्रतीत्तम् ६. ११७, १.
अप्रथेथाम् ४. २६, १.
अप्रऽमादम् १२. १, ७; ९; १८; १३. १, २३; ३, ११; १९. ४६, २.
अप्रऽमायुकम् १९. ४४, ३.
अप्रऽयातम् १९. ५५, १.
अप्रऽयावन् ३. ५, १.
अप्रऽयुच्छन् २. ६, ३; ६. ४, ३; ७. १०, २; १८. १, ३४.
अप्रऽहितम् २०. १०५, ३.
अप्रऽहितौ ६. २९, २.
अप्राक् १०. ४, २६.
अप्राक्षम् ७. ५७, १.
अप्राणत् १०. ८, ११.

अप्राणा ८. ९, ९.
अप्रात् १३. २, ३९; २०. १०७, १४.
अप्रायि १९. ४७, १.
अप्रायुऽभिः २०. ६४, ६.
अप्रियः ८. १२, २.
अप्रियम् ८. १९, ४; १५. १, ८.
अप्रियस्य ९. ५, ३१; ३२[२]; ३३[२]; ३४[२]; ३५[२]; ३६[२].
अप्रियाः ९. ७, ६.
अप्रिये ८. ६, २६; १२. १, ३०; १९. ५७, १.
अप्लवाःऽइव १९. ५०, ३.
अप्वाम् ९. १३, ९.
अप्वे ३. २, ५.
अप्सः ६. ४९, २.
अप्सरसः ४. ३७, २; ३; १२; ६. १११, ४; ७. ११४, ३; ८. ५, १३; ९. १२, १०; ११. ११, १५; १२. १, २३; ५०; १४. २, ९; ३४; ३५.
अप्सरसः ४. ३७, ३; ४; ५.
अप्सरसाम् ६. १३०, १.
अप्सरसौ ६. ११८, ३.
अप्सरसौ ६. ११८, १.
अप्सराऽपतेः ४. ३७, ७.
अप्सराभ्यः २. २, ५; ७. ११४, २.
अप्सराम् ४. ३८, १[२]; २[२]; ४.
अप्सरासु २. २, ३.
अप्सरसा ६. ४९, २.
अप्ऽसु १. ४, ४[२]; ६, २; ३०, ३; २. ३१, ५; ३. २१, १; २२, ३; ४. ८, ७; १०, ७; ३०, ७; ३७, १०; ६. ३८, २; ८०, ३; १२२, १; २; ३; ४; ५; ७. ८८, १; ९२, १; ८. १, ११; १०. ५, १५; १६; १७; १८; १९; २०; २१; ८, ४०; ११. २, २४; ४, १२; ७, १३; ८, २३; १०, ३४; १२. १, ३७; १३. १, १; २; ५०; २, ३०; ३, १५; १४. १, ३७; १६. १, ७; १७. १, ८; १३; १८. १, ४; ३, ६०; ४, ८९; १९. ३, ३[२]; ८, १; २७, १०; २०. ३३, १; १३९, ५.
अप्सुऽजाः १०. ४, २३.
अप्सुऽयोगैः १०. ५, ५.
अप्सुऽसंशितः १०. ५, ३३.
अप्सुऽसदः १२. २, ४; १६. १, १३.
अफलाः ८. ७, २७.
अफाणयत् २०. ९२, १०.
अबध्नत १०. ६, १८[२]; १९[२]; २०[२].
अबध्नन् १९. ६, १५.
अबध्नात् १०. ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २२; २३; २४; २५; २६; २७; २८; १४. १, १९; ५८.
अबन्धः ४. १६, ७.
अबन्धु ६. १२२, २.
अबन्धुऽकृत् ४. १९, १.
अबन्धुना २०. २१, ९.
अबलऽधन्वनः ३. १९, ७.
अबलान् ३. १९, ७.
अबलासौ ८. २, १८.
अबलेन ३. २९, ३.
अबिभः ६. ८१, ३; ८. ५, १४; १८. २, ५७; ३, ५४; ४, ५६.
अबिभेत् ८. १०, १.
अबिभ्यत् १९. ६५, १.
अबिभ्युषा २०. ४०, १; ७०, ३.
अबिभ्युषीः ३. १४, ३.
अबुध्यमाने इति २०. ७४, ३.
अबोधि १३. २, ४६.
अब्रवीः ५. ११, १.

अब्रवीत् १. ६, २; ५. १३, ९; १९, १०; ६. ११, २; ८२, २; ९. ४, १२; १०. ४, ४; १२. ४, ४२; १३. १, ५४; १५. ३, २.

अब्राह्मणः १२. ४, ४३; ४४; ४६.

अब्राह्मणाः ५. १७, ८; ११. १, ३२.

अब्रुवन् ५. १९, १२; ८. ११, २; ९.४, १४^{2}; १२. ४, ११; २२; १५. ३, १; २०. १३७, ५.

अब्रूताम् १५. १०, ३.

अभक्षि २. २५, १.

अभगः ५. ३१, ११.

अभंजन्त १९. ५६, ५.

अभजन्त ११. १२, ११.

अभयऽतमेन ७. १०, २.

अभयम् ४. २१, ४; ६. ३२, ३; ४०, १^{4}; २; ५०, १; ७. ९६, १; ८. १, १०; ११. २, ३१; १३. १, ५; १८. ३, ६१; १९. ३, ४; ८, ७; ९, १३; १४, १; १५, १; ४; ५^{5}; ६^{6}; १६, १; २७, १४; ४४, १; २०. २०, ७; ५७, १०; १२५, ६.

अभयम्ऽकरः १. २१, १; ८. ५, २२.

अभयाः १९. ४५, ४.

अभरः २०. ५५, २.

अभरत् ६. ६१, १; १३७, १; १०. २, ५; ८, २१; ११. ७, १९; १०, १२^{2}; १६; १७; १३. २, ३९; १८. १, २१; २, ३३; १९. ५३, ४.

अभरन् १५. ३, ३.

अभरन्त १९. ३३, ३.

अभवः २०. ४२, २.

अभवः ४. ६, ३; २०. ६८, ८; ९३, ८; १३७, १०.

अभवत् १९. ६, ४.

अभवत् ३. १०, १; १२; ४. १९, ६; ५. १२, ११; ७. १, २^{2}; ८. ४, २१; १२, १; ३; ५; ७; ९. १, ५; ४, ५; ५, २०; १०. २, १८; ८, २१; १०, २४; २६; २९; ३४; ११. ७, १६; १०, १; २; ८; १२. १, ६०; ४, ४९; १३. २, ३९; ४०; १४. १, ९; १५. १, ३^{7}; ४^{2}; ५; ६; ७, १; १८. ४, ३२^{2}; १९. ६, २; ६; ९; ५३, ४; २०. ११, १०; ३०, ४; ८७, ५.

अभवतम् ४. २६, १; २.

अभवन् १०. ७, १८; ३४.

अभवन् ५. १८, १०; १२; १९, १; ११; १०. १०, २०; २४; १९. ५४, १; ३.

अभागः ४. ३२, ५.

अभारिषम् ४. १३, ५; ६. ५२, ३.

अभावयत् ८. ५, ३.

अभि १. १, ३; ६, १; २७, ३; २९, १; २^{3}; ३^{3}; २. १, १; ४, ५; १०, ४; ११, ३; १३, १; ३. १, २; ३; २, ५; ६; ११, ८; १२, ८; १७, ४; १८, ६; २१, ५; २२, ६; २४, ६; २५, ४; ३०, १; ४. १, ३; ५; ८, २; ५; ६; १०, ७; ११, १०; १३, ७; १४, ६; ९; १५, ६; १६; १६, ७; ९; १९, ८; २१, ४; २७, ४; ३२, ३; ६; ७; ३६, १०; ५. १, ५; ६; २, ३; ३, ४; ४, २; ५, ९; ८, ९; ११, ७; १३, ४; १९, ४; ९; १५; २०, १; ३; ७; २१, ४; ५; ६; ९; २७, ९; ६. २५, १; २; ३; ३४, ४; ४०, २; ४१, ३; ४२, ३; ४७, ३; ५७, २; ७८, १; २^{2}; ७९, १; ९७, १; ९९, १; १०२, १; १२४, १; १२६, २; ३; १३६, ३; ७. १०, १; १५, १^{2}; ३६, ३; ३८, १; ७७, १०; ८७, १;

८९, २; ९८, १; ११४, ४; १२१, २; ८. १, ७; १२; २, ४; १४; १५; ३, ३; ९; ४, २; १९; २१[२]; २३; ६, २२; ७, २६; ८, ६; ८; ९; ९, ६; ९; १५; २१; ९. १, ८; ४, २२; २४; ५, ४[२]; ६; १२; १०, ८; १४, ३; २०; १५, ६[२]; १०. १, १५; २, १८; २७; ३, १३; १४; १५; ५, ३६; ४३; ६, १२; ११. १, ६; ३३; ३७; २, १; ८; १९; ३, १८; ११, ३; १२. १, १२; २९; ३३; ३४; २, २६; २७; ३, ४; ८[२]; ११; १२; १५; १६; १७; २६; २९; ३०; ३४[२]; ३७; ४१; ४२; ५२; ४, १०; १५; ७, ९; १३. १, १०; २०; २२; ३३; २, ९; २७; ४२; ४३; ३, २३; २५; १४. २, ३४; ३५; १६. १, ९; ९, १ १८. १, ५२; २, ४; ५०; ५१; ५२; ३, २[२]; १८; ४०; ५०; ७३; ४, १०; १३; २९; ६२; ६६; १९. ८, ५; १०, ४; १३, ७; ३१, १२; ४५, ४; ४६, १; २; ३; ४; ५[२]; ६; ७; ४९, २; २०. ५, १; ६, ७; ७, १; ८, १; ३; ९, १; १२, ६; १६, १; ११; १७, ७; १८, ४; २०, ५; २२, १; ४; ५; ३०, २; ३५, १०; ३६, १; २; ४९, ४; ५१, १; ५७, ८; ६१, ४; ६२, ८; ६४, २; ६५, १; ३; ६७, २; ६८, ११; ६९, ८; ७३, ५; ७६, ३; ७; ७७, ५; ८८, २; ९२, १; २; ८; ९९, १; १०४, १; १०५, १; १०७, ६; १५; ११२, १; १२१, १; १२४, ३; १२६, ८; ९; १९; १३७, ९; १४३, २.

अभिऽअंक्ता १०. १, २५.

अभिऽअक्रन्दत् १९. ३०, ५.

अभिऽअगच्छन् १६. ७, ९.

अभिऽअघायति ७. ७३, ३; १९. ५०, ४.

अभिऽअघायन्ति ५. ६, ९.

अभिऽअचक्षत १८. ३, ६६.

अभिऽअञ्जनम् ६. १२४, ३; १४. १, ६.

अभिऽअतिसृजामः १०. ५, १५; १६; १७; १८; १९; २०; २१; १६. १, ५.

अभिऽअर्धत्त ३. ११, ८.

अभिऽअध्वे ४. २८, २.

अभिऽअपक्रमीः १२. २, १८.

अभिऽअपप्तत् ६. १२४, २.

अभिऽअपेहि ७. ९३, १.

अभिऽअभवः ६. १२९, २.

अभिऽअवतनोमि ८. ८, २४.

अभिऽअवनिक्षि १०. ५, १५; १६; १७; १८; १९; २०; २१; १६. १, ४.

अभिऽअवर्तयन् १२. १, ५.

अभिऽअवर्षीत् ११. ६, ५; १७.

अभिऽअवसृजामि १६. १, ६.

अभिऽअसिच्यन्त १४. १, ३६.

अभिऽआक्रामम् १०. ७, ४२.

अभिऽआगात् ९. १५, ५.

अभिऽआचारम् १०. ३, २.

अभिऽआयत ४. २४, ६.

अभिऽआरोहति ३. २९, ३.

अभिऽआवर्तस्व ७. ११०, १; ११. १, २२.

अभिऽआवर्ते १०. ५, ३८; ३९; ४०; ४१.

अभिऽआववृत्स्व ३. १७, ९.

अभिऽइद्धः ७. ७७, ७; ९. १५, ४.

अभिऽउदतिष्ठत् १५. ८, २.

अभिऽउदिहि ३. २०, १०; १७. १, ६; ७.

अभिऽउदेत्य १५. ११, २; १२, २.

अभिऽऊढः १५. १५, ५.

अभिऽऊर्णुते १४. १, २७.

अभिऽएति १. २९, ४; ७. १२१, २; ९. १, ८.
अभिऽएहि ८. २, २.
अभिऽएमि ६. ११८, ३.
अभिऽकनिक्रदत् २०. ९१, ३.
अभिऽकृत्वरीः २. ८, २.
अभिऽक्रतूनाम् २०. ११, १०.
अभिऽक्रन्दति ८. ७, २१; ११. ६, ३; ४.
अभिऽक्रन्दन् ५. २०, २; ११. ७, १२.
अभिऽगच्छामि १६. ७, ११.
अभिऽघारितः ५. २१, ३.
अभिऽघारितौ १०. ९, २५.
अभिऽचक्र ३. ९, १.
अभिऽचक्षणम् ६. १२७, २.
अभिऽचक्षणाः ९. २, २१.
अभिऽचक्षे २०. १२३, २.
अभिऽचष्टे ८. ४, ८; ९. १५, २६.
अभिऽचस्कन्द ७. १२०, २.
अभिऽचारः ११. १, २२.
अभिऽचाराः १९. ९, ९.
अभिऽचारात् ८. २, २६; १०. ३, ७.
अभिऽचारिणः १०. १, ९.
अभिऽचेरुः ५. ३०, २; १०. १, १८.
अभिऽछायम् १३. १, ५७.
अभिऽजञ्जभानः ५. २०, ६.
अभिऽजित् ११. ९, १२; १९. ७, ४.
अभिऽजिताः १२. ३, ६.
अभिऽजित्य १२. ३, ३६; १९. ५४, ५.
अभितः ३. ५, ६; ७; ३०, ६; ४. ५, ६; १०. ८, ३; १७; १२. ३, ४२; १३. १, ३५; १४. १, ४५; १९. १६, २; २७, १५; २०. २१, ३; २५, १; ८७, ६; ८८, ३.
अभिऽतपन् १९. २८, ३.
अभितप्तम्ऽइव ४. ४, ३.
अभिऽतर्पयन्तीः १८. ४, ३९.
अभिऽदासतः १. २१, ३.
अभिऽदासति १. १९, ३; २१, २; २. २७, ७; ४. १९, ५; ६. ६, ३; १५, १; २; ५४, ३; ८. ४, ७.
अभिऽदासन् ६. ६६, १.
अभिऽदासन्तम् ८. ३, २५.
अभिऽदासन्ति ४. ४०, १; २; ३; ४; ५; ६; ७; ८.
अभिऽदासात् ५. ६, १०; १०, १; २; ३; ४; ५; ६; ७; ७. ११३, २; १२. १, १४; १९. १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
अभिऽदिग्धाः ५. १८, ८.
अभिऽदीपयन् ४. १९, ३.
अभिऽदुद्रोह ७. ९४, ३.
अभिऽदुन्वन् ५. २२, २.
अभिद्युऽभिः २०. २१, ५; ४०, २; ७०, ४.
अभिऽद्रोहम् ६. ५१, ३.
अभिऽधानी ८. ११, ५.
अभिऽधाय ८. ८, ५; ७; १९. ५०, ५.
अभिऽधावामि ६. ११९, ३.
अभिऽनक्षमाणाः १८. १, ४२; ४, ४६.
अभिनत् २०. २८, १; ३९, २.
अभिनत् २. ५, ५. २०. २१, ८; ९१, १२
अभिऽनन्दति ९. २, २.
अभिऽनन्दन् १९. ८, ३.
अभिऽनिवर्तस्व १०. १, ७.
अभिऽनिष्कारिणः १०. १, ३१.
अभिऽनिष्कृतात् १०. १, १२.
अभिऽनिष्पतन् ७. ६६, १.
अभिन्ने ४. २१, २.

अभिऽपर्यावर्तन्त १५. ७, ४.
अभिऽपश्यतः १०. ८, २४.
अभिऽपित्वम् २०. ७७, १.
अभिऽपित्वेषु २०. २५, ६.
अभिऽपूर्तम् ९. ५, १३.
अभिऽपूर्वम् ११. २, २२.
अभिऽप्रघ्नन्ति २०. ८३, २.
अभिऽप्रमन्वते ६. ८४, १.
अभिऽप्रहिताम् १०. १, १५.
अभिऽप्रेष्यामि १६. ७, २.
अभिऽभञ्जतीनाम् १९. १३, ९.
अभिऽभवः १. २९, ४.
अभिभवन्तीम्ऽअभिभवन्तीम् ९. ५, ३६.
अभिऽभाः १. २०, १; ५. ३, ६; ११. २, ११; १८. ४, ४९; १९. ४४, ७.
अभिऽभाम् ४. २८, ४.
अभिऽभुम् १०. ६, २९.
अभिऽभुवम् ९. ५, ३६.
अभिऽभूः २. २७, १; ६. ९७, १[४]; ९. ५, ३६; ११. १, ६; १४. २, १९; २०. ६२, ६; ९३, ८.
अभिऽभूतरम् २०. ५४, १.
अभिभूतिऽओजाः ४. ३२, ४; २०. ११, ६.
अभिऽभूतिः ६. ९८, २.
अभिऽभूते २०. २१, ३; १२५, १.
अभिऽभूयाय १९. ३७, ३.
अभिऽमनस्येत ११. ३, २५.
अभिऽमन्यते ६. ६, १.
अभिऽमातयः २. ७, ४.
अभिमातिऽजित् २. ६, ३.
अभिऽमातिम् ४. ३१, ३; १९. ३२, ६.
अभिऽमातिषु २०. १९, ७.
अभिमातिऽसहः ४. ३२, ४; ५. ३, ९; २०, २; ११.
अभिमातिऽसह्वौ २०. १९, ३.
अभिऽमातीः १८. २, ५९.
अभिमोद्ऽमुदः ११. ९, २६; १०, २४.
अभिऽयन्ति १०. ७, ४; ६.
अभिऽयन्ती ७. ४८, ३.
अभिऽयन्तौ ५. १, ५.
अभिऽयातः ११. २, १३.
अभिऽयाति ४. २९, ७.
अभिऽयुजः ७. ७७, ९.
अभिऽयुध्याः २०. ८७, ४.
अभिऽरक्षथ १०. ७, २३.
अभिऽरक्षमाणाः २०. ६३, २; १२४, ५.
अभिऽरक्षसि २०. १२६, ४.
अभिऽराष्ट्रः १. २९, ६.
अभिऽरूपाम् ८. ९, ९.
अभिऽरेषात् ४. ३५, १.
अभिऽरोरुदम् ७. ३९, १.
अभिलापऽलपः ११. १०, २५.
अभिऽवदति ९. ६, ४.
अभिऽवयसः २०. ९६, १.
अभिऽवर्गात् ११. २, ४.
अभिऽवर्गे ३. ५, २; ६. ५४, २.
अभिऽवर्तः १. २९, ३; ४.
अभिऽवर्तेन १. २९, १.
अभिऽववृधे १. २९, १.
अभिऽवारे १. ३२, ४.
अभिऽवीरः १९. १३, ५.
अभिऽवृता ९. १५, ७; १०. १०, १६.
अभिऽवृत्य १. २९, २.
अभिऽवृष्टाः ११. ६, ६.
अभिऽव्याधिनः १. १९, १.

अभिऽशस्ता ५. १८, १४.
अभिशस्तिऽपाः २. १३, ३; ४. ३९, ९; ५. १८, ६; ८. ७, १४; १९. २४, ५; ६.
अभिऽशस्तिम् ३. १, १; २, १.
अभिऽशस्तेः ७. ५९, १.
अभिऽशस्त्या ६. १२०, २; १२. १०, १२.
अभिऽशाचः १८. ४, ४४.
अभिऽशोकः १. २५, ३.
अभिऽशोचति ४. २६, ७.
अभिऽशोचनम् ४. ९, ५.
अभिऽशोचनात् २. ४, २.
अभिऽशोचयिष्णुः ६. २०, ३.
अभिऽशोचान् ४. ३७, १०.
अभिऽश्रावे १८. १, २९.
अभिऽश्रियौ ८. २, १४.
अभिऽश्रिषः १४. २, ४७.
अभिऽश्रुता ६. १३८, १.
अभिष्णक् २०. १२९, ५.
अभिष्टये १. ६, १; ६. ३, २; २०. ५१, ३.
अभिष्टिः २०. ११, ४; ७१, ७.
अभिष्टौ २०. ३७, ८; ९; ७७, ४.
अभिऽसंगत्य ११. १, १६.
अभिऽसंतपाति २. १२, ६.
अभिऽसंबभूव ३. २८, ५; ६.
अभिऽसंभूय ५. २८, ८.
अभिऽसंयन्ति ११. ७, ३.
अभिऽसंविशध्वम् ३. ३, ४; ६. ६४, २; ८. ५, २०; २१.
अभिऽसंविशन्ति १५. १७, ९.
अभिऽसंविशस्व ९. २, २५.
अभिऽसत्वा १९. १३, ५.
अभिऽसवनीः ९. ६, १६.
अभिऽसाचः १९. ११, २.
अभिऽसिक्तः १९. ३१, १२.
अभिऽसिञ्चामि ६. १२२, ५; १०. ९, २७; ११. १, २७.
अभिऽसिञ्चेत् ८. १५, १.
अभिऽस्कन्दम् ५. १४, ११.
अभिऽस्तुतः ९. २, १.
अभिऽस्तुताः ८. ७, ११.
अभिऽस्थितः ५. १४, १०.
अभिऽस्वरन्ति ९. १४, २२.
अभिऽस्वरा २०. ५४, ३.
अभिऽस्वरे १३. ३, २५.
अभिऽहतः ११. १२, २२.
अभिऽहतम् १९. ९, ९.
अभिऽहस्त्यम् ६. ३०, २.
अभिऽहिङ्कृणोत १२. ३, ३७.
अभिऽहितः ६. ६३, ३; ८४, ४.
अभिऽहितम् ९. ३, ८.
अभिहिताःऽइव १०. १, ३०.
अभिऽहितौ १४. १, ११.
अभिऽहुता ६. १३३, २.
अभिऽहुतः ६. ४, २.
अभिहुती इत्यभिऽहुती ६. ३, ३.
अभिऽह्वारे ६. ७६, ३.
अभीके २०. ९५, २.
अभीन् १९. २८, २.
अभीपतः ७. ४०, १.
अभीरुणम् ७. ९४, ३.
अभीशवः ८. ८, २२.
अभीशुना ६. १३७, २.
अभीषाट् १२. १, ५४; १३. १, २८.
अभुत्सत १२. ४, १.
अभुत्सि २०. १४२, १.
अभूः २. १३, ३; १९. २४, ६.

अभुः २. १०, ७; ५. ३, ११; ६. ८७, १; १८. ४, ५२.

अभूत् २. ९, २; ५. २२, ९; १२. २, २२; १८. २, ३७; ४, ६५.

अभूत् ६. ८१, १; ८. १, २१; १०. ४, २६; १३. १, ५; २०. १२६, २३.

अभूतन ४. ३७, ३; ४; ५.

अभूतम् १४. २, ५.

अभूताम् १९. १४, १.

अभूतिः ११. १०, २१; १२. ८, ८.

अभूत्या १६. ७, १.

अभूत्याः ७. १०५, १; १६. ५, ५; ८, ६.

अभूम १२. २, १३; १४. २, ६७; १६. ६, १.

अभूम १८. ३, २४.

अभूवन् २. ३१, ३.

अभूषन् ४. ८, ३.

अभैष्म १६. ६, २.

अभ्यसेताम् २०. ३४, १.

अभ्रः ९. १०, ६.

अभ्रऽजाः १. १२, ३.

अभ्रम् ४. १५, ९; ८. ११, ५; ९. १२, १८; १०. १, १३; ११. ३, ६.

अभ्रम्ऽइव ८. ६, १९; २०. १६, ५.

अभ्राणि ४. १५, १; ११. ९, २१.

अभ्रात् १२. ३, २५.

अभ्रातरःऽइव १. १७, १.

अभ्रातृऽघ्नीम् १४. १, ६२.

अभ्रातृव्यः २०. ११४, १.

अभ्रिऽखाते ४. ७, ५; ६.

अभ्रिऽभिः १०. ४, १४.

अभ्रियस्यऽइव २०. १६, १.

अभ्रियार्य २०. १६, १२.

अभ्रिये २. २, ४.

अभ्रे ११. ७, १३.

अभ्व्म् ४. १७, ५; ७. २४, १; १३. ६, ४.

अमंसत २०. १२६, १.

अमः १३. ८, ५; १४. २, ७१.

अमत २०. १६, ७.

अमतिः १०. २, १०.

अमर्तिः ७. १५, २.

अमतिम् ४. १०, ३; ७. ५२, ७; १२. २, ४८; १९. ३१, ११; ३४, ३; २०. १७, १०; २१, ४; ८९, १०; ९४, १०.

अमतेः २०. १७, ३.

अमत्रः २०. ३५, ९.

अमत्रम् २०. ७६, ७.

अमत्सत २०. ९२, ८.

अमदत् २०. १२६, १.

अमदन् २०. २१, ६.

अमन्तवः ४. ३०, ४.

अमन्दत २०. १४, ४; ६२, ४.

अमन्दिषुः २०. ५१, ४.

अमन्महि २०. ११६, २.

अमन्महि २०. ११६, १.

अमन्यत १५. ६, १९.

अमन्यमानान् २०. ३४, १०.

अमन्युताः १२. ३, ३१.

अमन्वत ७. १, १; २०. ४१, ३.

अमम्रिः ८. २, २६.

अमर्त्य ११. २, ३; १३. १, ४४.

अमर्त्यः ६. २६, ३; ७. ८९, १; ८. ३, २०; २६; ९. १५, ८; १६.

अमर्त्यम् १८. ४, ४१; २०. ६७, २.

अमर्त्यम् १९. ८, ३.

अमर्त्याः ६. ४१, ३; १२. १, २४.

अमर्त्याः ४. ३७, १२.

अमर्त्यान् ७. ९, ३.
अमर्त्येन ७. ९, ३.
अमर्त्यौ ८. ७, २०.
अमऽवान् १८. १, २४.
अमा ४. १८, ३; ५. ३, २; ११. ७, १९; १२. ४, ३८; ५३.
अमाऽउतम् ९. ५, १४; १२. ३, ५१.
अमाऽवास्या ७. ८४, २; १५. २, १४; १६, ३.
अमाऽवास्याम् १. १६, १; १५. १७, ९.
अमाऽवास्यायै ७. ८४, ३.
अमाऽवास्ये ७. ८४, १; ४.
अमाऽवास्ये ४. ३६, ३.
अमासि १२. ३, ३०; १८. २, ४९.
अमितः १. २७, ३.
अमितम् १०. ७, ३९; २०. ७७, ९.
अमितऽवीर्य १९. ३४, ८.
अमिता ४. २६, १.
अमितानि २०. ६५, ३.
अमित्रः ४. २२, २; ६. ६७, ३; ११. ११, १९; १२, २२; २६.
अमित्रम् २०. ९०, ३.
अमित्रऽयन्तम् ७. ८९, २.
अमित्रऽसहः १. २०, ४.
अमित्रऽसेनाम् ३. १, ३.
अमित्रऽसेनाम् ५. २०, ६.
अमित्रस्य १. २१, ३.
अमित्रऽहा ४. ३२, ३.
अमित्राः २. २८, ३; ५. २१, २; ८; ६. ६७, २; १०४, २; ८. ८, २; ११. १२, २१; २३; २०. ३४, ८.
अमित्राः ८. ८, १९.
अमित्राणाम् ३. १, ५; ५. २१, ९; ६. ६७, १; ८. ८, १; ११. ११, ३; ५; १८; २०; २३; १२, १६; २०[2].
अमित्रात् १९. १५, ६.
अमित्रान् १. १९, २; ३; ३. २, ५; १९, ३; ८; ४. २२, १; ५. २०, ८; २१, ४; ५; ६; ७; १२; ६. १०४, १; ११. ११, १२[2]; १८; २१; २३; १२, १; ३; १३; १८; १९; १९. १३, ८[2]; २०. ४६, १; ८०, २; ९०, २; १२५, १.
अमित्रेभ्यः ५. २१, ३; ६. १०४, ३; ११. ११, १; १५; २२; २४; १२, ६.
अमित्रेषु ५. २१, १[2]; ११. ११, ९; ११;२५.
अमिनात् २०. ११, ३.
अमिमाताम् १२. १, १०.
अमिमीत ५. १२, ११; ७. १५, २; ११. ५, ३.
अमी इति ३. ८, ५; २९, १; ५. ८, ५; २१, ८; ६. ९४, १; १०३, ३; ७. ८५, ४; ८. ८, १०; २४; ९. १५, १८; १३. २, १३.
अमीभ्यः ८. ८, २४.
अमीमदः ४. ६, ३.
अमीमदन्त १८. ४, ६१.
अमीमदम् ७. ७८, ३.
अमीमांसन्त १२. ४, ४२.
अमीमृणन् ३. १, २.
अमीमेत् ९. १४, ९.
अमीमेत् ९. १५, ६.
अमीवऽचातनः १. २८, १; ८. २, २८; १९. ४४, ७.
अमीवऽचातनीः ३, ७, ५; ६. ९१, ३.
अमीवा ७. ४३, १; २०. ९६, ११[2]; १२.
अमीवाः ७. ८९, १; ८. ७, १४; १९. ३४, ९; ४४, ७.

अमीवाम् ४. १०, ३.
अमीषाम् ३. २, ५; १९, ८; ८. ८, १९; ११. ११, २०; १२, १९; १२. २, ५५; १९. ५२, ४.
अमीषि २०. १२६, ८.
अमुक्थाः २. १०, ६.
अमुक्थाः २. १०, ६; १९. ४९, ८.
अमुक्षि १४. २, ४४.
अमुच्यत २०. ९२, १०.
अमुच्याः १६. ६, १०.
अमुच्ये १४. १, ५७.
अमुस्वः ७. ५५, १.
अमुस्वत् ३. ११, ८; २०. ३५, १०.
अमुस्वत १०. ६, ६; ७; ८; ९; १५; १७; २१.
अमुतः १. २०, ३; ५. ३, ११; ८, ३; ७. १२०, १; ८. ९, ६; ११. १२, ९; १४; १४. १, १७; १८[२]; १८. ३, ३८.
अमुत्र ८. १, १८; ९. ३, १०; १३. १, ३९.
अमुत्रऽभूयात् ७. ५५, १.
अमुम् २. १२, ४; ३. ३, १; ५. ८, ७; २२, १२; ६. ७५, १; १३५, २; ३; ८. ६, १२; ९. ११, १३; १०. ५, ४४; १६. ८, २[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२]; १९[२]; २०[२]; २१[२]; २२[२]; २३[२]; २४[२]; २५[२]; २६[२]; २७[२]; २८[२]; २९[२]; ३१[२]; २०. ७०, १२.
अमुया ५. २२, १; ७. ५८, ६; १०४, १; १४. १, २७; २०. ७४, ५.
अमुर ५. १, ९; ११, ५.
अमुषिता १. २७, ४.
अमुष्णाः २०. ७५, २.
अमुष्णात् २०. ९१, ६.
अमुष्मात् १२. ८, ११.
अमुष्मिन् ११. ६, १८; १२. १०, ११.
अमुष्मै ७. ११८, १; १६. ६, ७; ११.
अमुष्य ६. १३५, १; २; ३; ९. १४, १०.
अमुष्य ६. १३०, ३.
अमुष्याः ६. १३८, ४; ५; ८. ८, १६; १०. ५, ३६; ४४; १६. ७, ८; ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१.
अमुष्याः ४. १६, ९.
अमू १३. ६, ७.
अमू इति ३. ७, ४.
अमूः १. ४, २; १७, १; २७, १; ६. ६७, १; ९. ४, ६; ११. ११, १८; १२, २०[२].
अमून् ५. ८, ८; ६. २९, १; ८४, २; ८. ८, ३[२]; ४; ८; ९; १०; ११; २४; १०. १, ६; ३१; ११. १, २०.
अमूम् ४. ३०, ७; ६. ९, ३; १२६, ३; १३९, ३; ७. ११८, १; ८. ८, २; १४; १५; १७; १८; ११. १२, १३; १९. ५३, ९.
अमूमुहत् ३. २, २.
अमूलायाम् ५. ३१, ४.
अमूजत ६. ११३, १.
अमृत १०. ४, २६.
अमृतऽअसुः ५. १, १; ७.
अमृतः ८. २, १३; २६; १०. ८, ४४; १२. २, ३३; १३. १, ४३; १६. ४, २.
अमृतऽगर्भः ६. ४६, १.
अमृतऽत्वम् ७. १११, १; ९. १५, १; १५. १७, १०; १८. ४, ३७; १९. ६४, ४.

अमृतऽत्वस्य १९. ६, ४.
अमृतऽत्वे १८. ३, ६२.
अमृतम् १. ४, ४; २. १, ५; ३. ३०, ७; ४. २, २; १५, १०; २३, ६; २४, ४; ३५, ६; ५. ६, ८; २८, ११; ७. १८, ३; ८. १, ६; ७, २०; ९. १, १; २; १०. २, १४; ३, २५; ६, १४; ७, १५; १०, २६; २९; ११. १, २८; ८, २३; ९, १३; १२. १, ८; १५; ३, ४; १३. १, ७; ३४; ६, ४; १८. १, ३२; ३, ४१; ६२; ४, ३९; १९. ६, ३; २६, १; ४३, ७; ५३, २; २०. २५, ५.
अमृतस्य २. १, २; ३. १२, ६; ४. ७, १; ९, ३; ११, ६; ५. ४, ३; ४; २८, ७; ३०, १४; ६. ४४, ३; ९५, १; २; १२१, ३; ७. ४९, २; ८. १, १; २, १; ७, १२; २२; ९. १, ४; १४, २२; ११. ७, ७; १२. ३, ४१; १३. २, १५; ३, २०; १४. १, ६१; १८. १, २५; ३४; १९. ३९, ६; ७; ८.
अमृता १०. ८, २६.
अमृताः ३. ३१, ११; ४. २, ६; १३. १, २४; १८. ३, ५३; १९. ११, ५.
अमृतात् ८. २, १३.
अमृतानि ४. ८, ३; ५. १, ३; ६. १, ३; ८. १, ५.
अमृताम् १८. २, ३३.
अमृताय १४. १, ४२. २०. ११, २.
अमृतासः ७. ७७, ३; १२. ३, २७; १८. १, ३; ३, ३९.
अमृते १०. ८, ४१; ११. ९, ११.
अमृतेन ३. १२, ८[2]; ९; ५. २८, ८; ७. १२३, १; ९. ३, २३; १०. २, २९; ११. ७, ५; २३; १८. ४, ४; १९. १९, १०.
अमृतेभ्यः १. ३१, १.
अमृतौ ९. ३, १९.
अमृध्राम् २०. ३६, १०.
अमृशत् १३. १, ८.
अमेनयः ५. ६, ९.
अमेनीन् ५. ६, १०.
अमोक् १२. २, १२.
अमोक्यैः ३. ६, ५.
अमोचि १३. २, ८.
अम्नः ८. ६, १९.
अम्ब २०. १२६, ७[2].
अम्बयः १. ४, १.
अम्भः १३. ५, १; ६, १; ८, ५; ६.
अयः ११. ३, ७; १८. ३, २२; १९.५०, ६.
अयः ७. १०२, १.
अयःऽजालाः १९. ६६, १.
अयःऽदंष्ट्रः ८. ३, २.
अयःऽपात्रम् ८. १३, २.
अयःऽमुखाः ११. १२, ३.
अयक्ष्मऽतातिम् ४. २५, ५.
अयक्ष्मम् ५. २९, १३.
अयक्ष्मम्ऽकरणीः १९. २, ५.
अयक्ष्माः ३. १२, ९; ९. ३, २३; १२. १, ६२.
अयक्ष्मान् ६. ५९, २.
अयच्छत् २०. ३५, ११.
अयच्छत् १. १६, २; २. १३, २; ५. १७, २; १०. २, १५; ११. ७, १५; १९. २४, ४.
अयच्छन् ६. १२८, १; ११. १०, ३१.
अयजन् ७. ११५, २.
अयजन्त ७. ५, ३; ५.

अयजन्त ७. ५, १; ५; १९. ६, ११.
अयज्ञियः १२. २, ३७.
अय॑ज्युम् २०. ७५, २.
अय॑ज्वनः ३. २४, २; ११. २, २३.
अयत् ४. ३, ६; ६. ११८, २.
अयताम् १. २२, १.
अय॑ति १३. १, ५८; १९. ४९, १०.
अयति ४. ३, ५; ६. ६, २; २०, १; १०. १, १३; १९. ४९, १०[३].
अयन् १८. ३, २१; २०. ९४, ६.
अय॑नम् ५. ३०, ७; १०. १, ८; १०, २१; १८. ४, ८[३]; १५; १९. ७, २.
अय॑ना १०. १, १६.
अयन्ताम् ११. १२, ८.
अयम् १. ७, ४; ८, २; १०, १; २; २२, २; २. ४, ३[३]; ६; ९, २; ३; २८, १; २९, २; ३; ३१, ७; ३. २, २; ४, ५[२]; ६; ५, १; ८, ३; १०, ८; १३, ७; १४, ६; २०, १; ४. ५, ६; १३, ४; ६[४]; २२, २; ३[२]; ४; ३२, ६; ३८, ७[२]; ५. ९, ७; २२, २; २६, १२; २७, ४; २८, ९; २९, ६; ७; ८; ९; १२; १३; ३०, ११; १७; ६. ५, ३; १६, ३; २०, ३; ३१, १; ४३, १[२]; २; ४४, १; ६०, १; ६८, १; ३; ७२, १; ७४, १; ७८, १; ७९, १; ८१, १; ८५, १; ८६, १; ८७, ३; ८८, १; १०२, १; १११, १; ११२, १; १२०, १; १२१, २; १३०, १; १३४, १; ७. २३, १; ३१, १; ३४, १; ५५, ५; ६; ५८, ४; ६४, १; ७७, ४; ८. १, १; १८[२]; २, ५; ८; ५, १; २; ४; १६; ८, ८; १७; ९. ४, २१[२]; १५, ७; १४[३]; १०. १, ८; १५; ३, १; ३; ४[३]; ५; ६; ८; १०; ११; ४, १५; ६, २; ४; २२; २३; २४; २५; २६; २७; २८; ३१[२]; ३२; ११. १, २; १५; २, ११; १२, ५; १२. २, ८; ४३; ३, १४; १३. १, १६[३]; ३, १५; १४. १, ३३; १५. १०, ७; १५, ३; ६; १८, ३[२]; १७. १, २४; १८. १, ४८[४]; ३, ४; १४; १५; ५३; ४, १५; ३७; १९. २७, १०; ३१, १०; १४; ३२, ९; १०; ३३, १; ३४, ४; ३६, ५; ३९, २; ३; ४; ५४, ५; २०. ५, १; ५; ६; ८, २; ४५, १; ४८, ४; ५३, १; ५७, ११; १०४, २; १२६, ३; ९; १८; १९; १३९, ४[२]; १४०, १; १४२, ३.
अय॑सा ५. २८, ५.
अय॑सि ५. २८, १.
अय॑से २०. १५, ३.
अयस्मय॑म् ५. २८, ९.
अयस्मया॑न् ६. ६३, २; ८४, ३.
अयस्मयी॑ः ४. ३७, ८.
अयस्मये॑ ६. ६३, ३; ८४, ४.
अयस्मये॑न ७. १२०, १.
अयस्मयै॑ः १९. ६६, १.
अया ७. ३, १; १९. १२, १; २०. ३६, ६; ६३, ३; १२४, ६.
अया॑ः २. १२, ७.
अयाचन् १२. ४, २०; २४.
अया॑त् १२. ११, ३; १४. १, ६; १०.
अया॑तम् १०. ८, ८; १४. १, १४; १५.
अया॑तुम् ८. ४, १६.
अयाम १२. ३, १८.
अयामः १९. ९, १४.
अया॑मि २०. १२, २.
अयाशव॑ः ८. ६, १५.
अयास्य॑ः २०. ९१, १.

अयुक्त १३. २, २४; २०. ४७, २१; १२२, १.
अयुक्त १३. २, ८.
अयुञ्जन् २०. २३, २.
अयुतः १९. ५१, १[६].
अयुतम् १९. ५१, १[६].
अयुतम् ८. २, २१; ८, ७; १०. ८, २४.
अयुवन्त ४. २३, ५.
अयैः ४. ३८, ३.
अयोध्यः ५. २०, १२; १९. १३, ७.
अयोध्या १०. २, ३१.
अयोध्येन १९. १३, ३.
अरंसत १. १७, ३; १४. २, ५.
अरगरांटेषु ६. ६९, १.
अरज्यत १५. ८, १.
अरणः १. १९, ३; ५. ३०, २; ७. ११३, १.
अरणम् ५. २२, १२.
अरणाःऽइव २०. ११६, १.
अरणाय ६. ४३, १.
अरणिम् १. १८, २.
अरणी ७. ११३, १.
अरणी इति १०. ८, २०.
अरणेभिः ७. ५४, १.
अरण्यम् १२. १, ११; ५६.
अरण्यात् २. ४, ५.
अरण्यान्याः १२. २, ५३.
अरताम् १४. २, १६.
अरत्नीन् १९. ५७, ५.
अरत्नौ २०. ९६, ४.
अरथाः ११. १२, २४.
अरन्धनायः २०. २१, १०.
अरन्धयः २०. ३७, २.
अरन्धयत् १०. ४, १०; १६; १७.
अरपः १८. १, ५१.
अरपाः १. २२, २; ४. १३, ४.
अरम् १. ५, ३; २०. ३१, २.
अरम्ऽकृतः २. १२, ७; १८. २, १.
अरम्ऽकृतम् १२. १, २२.
अरम्ऽगमः ३. १३, ५.
अरम्ऽगमासः १३. २, ३३.
अरम्ऽघुषः १०. ४, ४.
अरम्णात् २०. ३४, २.
अररुः ६. ४६, १.
अररुषीः १९. १५, २.
अरस ६. १३८, ३.
अरस ४. ६, ६.
अरसः ४. ६, ६; ५. १६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; २२, २.
अरसऽतमम् ५. १३, ९.
अरसऽतराः ७. ८०, १.
अरसम् ४. ६, १; ६[२]; ७, २[२]; ५. ४, ९; ८, ६; १३, ८; १०; ११; ६. २९, ३; १००, ३; १३८, ३; ७. ५८, ३; ७; १०. ४, ३; ४; ११. १२, १७; १९. ३४, ३.
अरसस्य ४, ६, ६; ७. ५८, ५.
अरसा १०. ४, ८.
अरसाः ५. १३, ७.
अरसाः २. ३१, ३; ४. १८, १; ९. २, १०; १९. ३४, ३.
अरसान् २. २७, १; २; ३; ४; ५; ६; १९. ३४, २; १०; ३५, ५.
अरसासः १०. ४, ९.
अराः ३. ३०, ६; १०. ८, ३४.
अराजन् ५. १८, १०.
अराजिषुः २०. २८, ४; २९, ५.
अराटकी ४. ३७, ६.
अरातयः १. २९, २; ५. २३, २; ६. १२९,

१; २; ३; ११. १०, २१; १३. १, ५९; १४. २, ११; १९. ५०, ३; २०. ७४, ४; ९५, ४. १३९, १.
अरातये ५. ७, १; ३.
अरातिः २. ७, ४; ६. १२४, ३; १२. ३, १७.
अरातिऽदूषणः १९. ३४, ४.
अरातिऽदूषिः २. ४, ६.
अरातिम् १. १८, १[२]; २. १०, ७; ३. १, १; २, १; १५, १; ५. ७, ३; ६; ८. २, १२; १२. २, ३; ४५; १९. ३१, ११.
अरातिऽयात् ४. ३६, १.
अरातिऽयोः १०. ६, १.
अरातिऽहम् १९. ३५, २.
अरातीः १. २, २; १०. ५, ३६; १३. १, २०; १६. ९, १.
अराते ५. ७, ८.
अराते ५. ७, १; २; ७; १४. २, १९.
अरात्या ३. ३१, १.
अरात्याः १०. ३, ७; १३. ८, २.
अरात्यै ५. ७, १०.
अरात्सीः ५. ६, ५; ६; ७.
अराधसः १२. १०, १४; ११, ४; २०. ९३, २.
अराधसम् ५. ११, ७; ८; २०. ६३, ५.
अराम ११. २, १७.
अरामहि ११. २, ७; २०.
अरायऽक्षयणम् २. १८, ३.
अरायऽचातनम् २. १८, ३.
अरायम् २. २५, ३.
अरायाः १२. १, ५०.
अरायान् ८. ६, ४; ५; ६; १२; ११. ८, १६; १६. ६, ७.
अरायेभ्यः ८. २, २०.
अराय्यः १. २८, ४; २. १४, ३; ४. १७, ५; १८, ७; ८; ७. २४, १.
अराव्णे २०. १८, ५.
अरिः ७. ९३, १[२]; १३. १, २९.
अरिः २०. ६८, ६; ७१, १६.
अरिच्यत १९. ६, ९.
अरिणात् २०. ३४, ३; ९१, १२.
अरित्राणि ५. ४, ५.
अरिप्राः १०. ५, २३; १६. १, १०.
अरिप्रे इति ५. २, ९; २०. १०७, १२.
अरिष्ट १९. ७, ३.
अरिष्ट ८. २, २४.
अरिष्टः ४. ५, ७; ७. ५५, ५; ८. २, ८; १०. ३, १०.
अरिष्टऽगुः १०. ३, १०.
अरिष्टऽतातये ३. ५, ५; ५. ३०, १२; ६; १९, २; ८०, २; ८. २, ६; ५, २०; ७, ६; २७; १९. ३८, ३.
अरिष्टतातिऽभिः ४. १३, ५.
अरिष्टऽनेमिम् ७. ९०, १.
अरिष्टऽवीराः ३. १२, १.
अरिष्टाः ५. ३, ५; १०. ५, २३.
अरिष्टानि १९. ६०, २.
अरिष्टासः ७. ५२, ७; १९. ४७, २; २०. ८९, १०.
अरिष्टासु इत्यरिष्टऽअसु १४. २, ७२.
अरिष्यन्तः २. ४, १; १९. ५०, ३; २०. १४३, ८.
अरुः ५. ५, ४.
अरुःऽस्राणम् २. ३, ३; ५.
अरुक्षः १७. १, ८; २५; २६.
अरुक्षत् २०. ९१, १०.

अरुक्षत् ३. ५, ५; ८. ५, २०; ११. १, १३; १६; १२. ३, ४२; १८. ४, १४.

अरुक्षाम १४. २, ८.

अरुणः ५. २२, ३; ११. ७, १२.

अरुणम् १२. १, ५२; १३. २, ३६; ८, ६; २०. ८७, १.

अरुणाः १०. २, ११; ११. १२, ७.

अरुणार्य ६. २०, ३.

अरुणीः १८. ३, २१.

अरुणीनाम् १८. ३, ४३.

अरुणैः ११. १२, २.

अरुदत् १४. २, ६०.

अरुधन् १८. २, २७.

अरुन्धति ४. १२, १; ५. ५, ५; ९; ६. ५९, १.

अरुन्धती ६. ५९, २.

अरुन्धतीम् ८. ७, ६.

अरुन्धते १९. ३८, १.

अरुषः २०. १७, ९.

अरुषम् २०. २६, ४; ४७, १०; ६९, ९; ९२, १३.

अरुषासः ३. ३, २.

अरुषीः २०. २२, ५; ९२, २.

अरुहः १९. ६५, १.

अरुहत् १२. २, १२; १३. १, २६; २, ८; २५; १९. ४९, २.

अरुहन् १८. १, ६१^{२}.

अरुहन्त १९. ४९, २.

अरुहम् ४. १४, ३^{२}.

अरूरुपः ४. ६, ३.

अरेपसः ७. २३, २.

अरोगणम् २. ३, २.

अरोचथाः ३. २०, १.

अरोचथाः १३. ३, २३.

अरोचयः २०. ६२, ६.

अरोचयत् २०. ११, ४; ११८, ४.

अरोदयत् २०. ९१, ६.

अरोहत् १४. १, १२; २, ३०; १५. ३, ९; १८. ३, ४०; १९. ६, २.

अरौत् १०. ४, २६.

अर्कऽअश्वमेधौ ११. ९, ७.

अर्कः ४. १५, ५; २४, ५; ६. ७२, १; १३. ३, २३; २०. १६, ४; २५, ६.

अर्कम् ३. ३, २; ९. १५, २; १०. ८, ३; १२. २, ५५; १३. १, ३३; १८. ३, ४०; ४, २९; २०. ३५, ५; ८; ६३, ३; ९१, ५; ९३, ७; ११०, १; ११९, २; १२४, ६.

अर्कस्य २०. ७२, ३.

अर्काः २०. १६, १.

अर्किणः २०. ३८, ४; ४७, ४; ७०, ७.

अर्केण ९. १५, २; २०. १६, ९.

अर्केभिः २०. ३८, ४; ४७, ४; ७०, ७.

अर्कैः १८. ३, ४७; २०. ११, १; १२, ६; १६, ६; ७७, ४; ९०, ३; १४२, ३.

अर्च २०. ५१, ३.

अर्च २. १९, ३; २०, ३; २१, ३; २२, ३; २०. २२, ४; ५१, १; ९२, १.

अर्चत २०. ९२, ५^{२}.

अर्चत २. २३, ३; ७. ८७, १; १८. ३, ६३; ४, ५४; २०. ३०, २; ९२, ५^{२}; ९५, २.

अर्चति २०. ११७, ३.

अर्चति २०. ४०, २; ७०, ४; ७१, १६.

अर्चनानाः १८. ३, १५.

अर्चन्ति १. २, ३; १२. १, ३८.

अर्चन्ति १३. १, ३३; २०. १२, ६.

अर्चन्तु २०. ९२, ५.

अर्चन्तु २०. ११०, १.
अर्चात् २०. ७७, ३.
अर्चाम ६. २७, १.
अर्चामि ७. १९, १; १८. १, ३१.
अर्चिः १. २५, २; २. १९, ३; २०, ३; २१, ३; २२, ३; २३, ३; १२. १, ५१; १८. २, ८.
अर्चिऽभिः ८. ३, २३.
अर्चिषा ५. २९, १५; ६. ३२, ३; ८. ३, २; ११; १३; १७; २५; १०. ५, ४९; १३. २, २; १९. ६५, १[२].
अर्चींषि ११. ७, १३.
अर्चै २०. ३६, १.
अर्जुनः १३. ३, २६.
अर्जुनऽकाण्डस्य २. ८, ३.
अर्जुनम् २. ३२, २; ५. २३, ९; २८, ५; ९.
अर्जुनाः ४. ३७, ५.
अर्जुनि २. २४, ७.
अर्णवत् ५. २, ८; २०. १०७, ११.
अर्णवम् ७. ८६, १; १३. १, ३६; २, ११; १४. १, २३; १८. १, १.
अर्णवस्य २०. ९१, १२.
अर्णवात् १. १०, ४; १३. १, २६.
अर्णवे ३. ६, ३; ११. १०, २; ६; १२. १, ८; ६०; १३. १, ४०; २, २.
अर्णवेन ५. ६, ४.
अर्णांसि २०. ३५, १२; ७७, ७.
अर्तिष्ये १४. १, ५६.
अर्त्व्यैः ८. १३, ३.
अर्थम् १२. २, २३; १५. १७, ८; २०. ७६, ५; ९२, १४.
अर्थाय १. ७, ६.
अर्दति १२. ४, ३.
अर्दय ४. १५, ६.
अर्दय ६. ६५, १.
अर्दयन् ६. ४९, २.
अर्दयाति ४. १५, ११.
अर्धऽऋचेन ९. १५, १९.
अर्धः ८. ९, १.
अर्धकऽघातिना ११. २, ७.
अर्धऽगर्भाः ९. १५, १७.
अर्धऽभाक् ६. ८६, ३.
अर्धम् ९. १४, १७; १३. १, ४१.
अर्धम् ५. १, ९; १०. ८, ७; १३; ११. ६, २२.
अर्धऽमासाः १०. ७, ५; ११. ९, २०; १५. ६, १७.
अर्धऽमासानाम् १५. ६, १८; १६. ८, २३.
अर्धऽमासे ८. १२, ५; ६.
अर्धयन्ति ७. ८५, ४.
अर्धे ४. १, ६; ९. १४, १२.
अर्धेन ५. १, ९[२]; १०. ८, ७; १३; ११. ६, २२.
अर्पणेन १२. ३, २२.
अर्पय ५. २२, ६; ६. ६६, १; १०. ३, १५; ९, १.
अर्पयतम् ८. ४, १.
अर्पितम् ९. १४, १२.
अर्पिपम् १२. १, ३५.
अर्बुदस्य २०. ९१, १२.
अर्बुदिः ११. ११, ४; २३.
अर्बुदे ११. ११, ५; १२, ५.
अर्बुदे ११. ११, १; २; ३; ७; ८; ९; १०; ११; १३; १४; १५[२]; १८; २०; २२; २४; २५; १२, २३.
अर्भकः २०. ९२, १२.

अर्भकम् ७. ५८, ६; ११. २, २९.
अर्भकाः १. २७, ३; १९. ३६, ३.
अर्भस्य ७. ५८, ३.
अर्भे २०. ५६, १; ७०, ११.
अर्यः ६. ६३, ४; १८. ३, २३; २०. १८, ५; ३४, ४; ५; ५६, ६; ६६, १; ८५, ४; ८९, १; ९५, ४; १२६, १; ३.
अर्यऽपत्नीः २०. १७, ८.
अर्यमणम् ३. २०, ७; १४. १, १७; २०. १६, २.
अर्यमन् ६. ६०, २.
अर्यमा १. ११, १; १८, २; ३. १४, २; २०, ३; ५. ५, १; २८, १२; ६. ४, २; ६०, १; १०३, १; ९. १२, ७; ११. ८, ४; १३. ४, ४; १४. १, ५०; २, १३; ४०; १९. ९, ६; १०, २.
अर्यम्णः ३. ५, ५; १४. १, ३९; २, ५.
अर्यम्णा २. ३६, २; १४. १, ३४.
अर्वतः १०. ४, ७; १९. ५०, ५; २०. ९८, १.
अर्वता २०. ७०, १८.
अर्वताम् ४. ९, २; २७, ३.
अर्वतीःऽइव १०. ४, २१.
अर्वत्ऽभिः २०. ३१, २; ३.
अर्वन् ६. ९२, २.
अर्वन्तः १९. ११, १.
अर्वा ४. २१, ४; २०. ११७, १.
अर्वाक् ४. २५, ६; ५. ११, ६; ८. १, १०; १०. १, १६; ११. ७, १०; ११; १८. १, ५१; १९. ५, १; २०. ७१, ११; ७६, ३; ११३, १.
अर्वाके २०. १४१, ५.
अर्वाङ् ३. २, ३; ४. १५, ११; ३२, ६; ३८, ६; ५. २२, ११; २६, १२; ८. १, ९; २, २; १०. ८, १७; २९; १३. २, ३१; ३, १६; १७. १, १७; १८. २, ६०; ३, ४८; २०. ८, २; १२, ७; १३, ४; २३, ८; ९४, २.
अर्वाचः ९. १४, १९.
अर्वाची ३. १७, ८; ६. ६७, ३.
अर्वाचीनम् १०. ५, २२; २०. १९, २.
अर्वाचीनम् ३. १६, ६.
अर्वाञ्चः ९. १४, १९.
अर्वाञ्चम् ५. ३, ११; ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; २०. २३, ९; २८, २; ३९, ३.
अर्वाञ्चौ ५. २६, १२.
अर्वाणः १८. ३, १९.
अर्वाऽवतः २०. ६, ८; २०, ४; ५७, ७.
अर्वाऽवतम् २०. ६, ९.
अर्वाऽवति २०. ११२, ३.
अर्षणीः ९. १३, १३; १६; २१.
अर्षत् १०. ४, १.
अर्षत ६. २८, २.
अर्षतु ४. ३, २; १९. ४७, ७.
अर्षसि १३. २, १३.
अर्षसे १८. ४, ६०.
अर्हति १०. १, २६; १४. १, २९; १९. २२, २१; २३, ३०; २६, १.
अर्हते २०. १३, ३.
अलजेः ९. १३, २०.
अलपन् ८. २, ३.
अलम् ६. १०९, १.
अलसाला ६. १६, ४.
अलाबुना ८. १५, १.
अलाबुऽपात्रम् ८. १४, १४.

अलिंशः ८. ६, १.
अलिक्लवाः ११. ११, ९.
अलिक्लवेभ्यः ११. २, २.
अलिप्सत ६. ५२, २.
अलीकाः ५. १३, ५.
अलुभ्यतः ३. १०, ११.
अलगण्डून् २. ३१, २; ३.
अल्पः ११. ३, २४.
अल्पऽपशुम् १२. ४, २५.
अल्पंशयून्ऽइव ४. ३६, ९.
अल्पे ४. १६, ३.
अर्व १. ११, ३; ४[२]; ५; ६; २. ५, ६; ३. ३, ६; ४. १, ७; १५, १२; २२, ७; ३५, ७; ५. ३, १०; ६, ६; ११, ३; १३, ६; १४, १; २[२]; १८, ९; ११; १९, ७; २०, ८; २१, १; २७, ११; ६. १६, ३[२]; २६, १; ४२, १; २; ६५, १[३]; ७६, ४; १२०, २; १३४, १; ७. ८, १; ४२, २; ५७, २; ७५, १; ८८, ३; ९५, ३; ९९, १; ११२, १; ८. १, ४; ४, १७; ६, ३; १६; २०; ८, २०; ९. २, १०; १४; ४, १९; ५, ३; ५; २२; ६, ९; ९, २; ४; ६; ८; १४, १०; १०. ४, ३; ११. १, १७; १२, ८; १२. १, ५८; ३, ४१; ४६; ४, ३९; १३. १, ३०; ३२[२]; २, १५; १४. २, ५२; १५. ११, ४; ६; ८; १०; १३, २; ४; ६; ८; १०; १६. ७, ४; ११; १८. २, १०; ५६; ३, ६०; ४, १२; १३; ३७; ६१; ६९; १९. ३, ४; ९, ८; ३६, ४; ५; ४४, ७; ४६, २; ६५, १; ७२, १; २०. १५, ६; २९, ४; ६७, १[२]; ७३, ५; ७७, २; ७९, २; ९२, ६; ९३, १; ९५, ३; १२६, १०; १२७, ७; ११.
अव ३. १६, ३; ७. ५२, ४; १३. १, ४३; २०. ७०, १०; ८१, २; ९२, २१.
अवऽअतिरः २०. ७५, २[२].
अवऽअमृक्षत् ७. ६६, २.
अवऽअसृजत् १४. १, १३; २०. ३४, १३.
अवऽअसृजन् ४. ६, ७.
अर्वः २०. ४४, २; १४१, ३.
अवः ९. १४, १७; १८[२]; १३. १, ४१; २०. २५, २; ९१, ४.
अर्वःऽभिः ७. ९६, १; १९. १०, १; २०. १२५, ६.
अवकाऽअदान् ४. ३७, ८; ९; १०.
अर्वकाऽउल्वाः ८. ७, ९.
अवऽकेशः ६. ३०, २.
अवऽक्रक्षिर्णम् २०. ८५, २.
अवऽक्रामन् ४. ११, १०; १३. १, २०.
अवऽक्रामी ५. १४, १०.
अर्वऽक्षामम् ६. ३७, ३.
अवऽक्षिपन् २०. १६, ४.
अवऽघ्नती ११. १, ९.
अवऽचरन्तिका ५. १३, ९.
अवऽचाकशत् ६. ८०, १; १३. २, १२; ४, १; २०. १७, ६.
अवत १९. १, २; १३, ११; ७२, १.
अर्वतः ४. २, ३.
अर्वऽततम् २. ७, ३.
अवतम् ६. ४, ३; १४. १, ३५; ३६; २०. ९१, १२.
अवतस्थिऽवांसम् २०. १३७, ८.
अवताः २०. ८८, ३.
अवताम् ५. २४, ३; ५; २७, ८; ७. १३, १; १८. ३, ३८.

अवति ८. ७, २१; २०. ३४, १९.
अवति १. १६, २; ८. ४, १२.
अवऽतिष्ठति ६. ४३, २; ७. ८०, ३.
अवतु २. १२, ४; ५. २४, १; २; ४; ७; ८; ९; १०; ११; १२; १३; १४; ७. २१, ५; १९. १३, ७; ४९, ६; ७; ८; ९.
अवऽतोकाम् ८. ६, ९.
अवत्ऽकम् २. ३, १.
अवत्ऽतरः १८. ३, ५.
अवथ २०. ९१, ११.
अवथः ४. २९, १; २; ३[२]; ४[२]; ५[२]; ६[२].
अवऽदधुः ५. ३१, ८.
अवदन् ७. १, १.
अवदन् ५. १७, १; १२. ४, ४९.
अवदन्त ५. १७, ६; ६. १०९, २.
अवद्यम् ७. ९४, ३; १८. ३, ५८.
अवद्यऽवत्याः ७. १०८, १.
अवद्यात् २. १०, ६; ५. ६, ८; १२. २, ४७; ४८.
अवद्यानि ५. ११, ७.
अवऽधावति २. ३, १.
अवधिषम् ७. ७३, ४; ५.
अवधीत् ९. २, ११.
अवधीत् २०. ७, २.
अवऽधीयमाना १२. ८, ३.
अवध्वंसःऽइव ५. २२, ३.
अवऽनद्धम् ९. ३, ८.
अवनिः २०. ६८, १०.
अवनीः २०. ३५, १०.
अवन्ति १८. ३, २४.
अवन्तु १८. ३, १९.
अवन्तु २. १३, ५; ३. १९, ५; २३, ६; ४. १५, ७; ९[२]; २७, १; ५. २४, ६; १५; १६; १७; ७. ५१, १[२]; १८. १, ४४; ४७; ३, ४९; १९. ४५, १०.
अवन्वत ५. ४, ३; ४; ६. ९५, १; २.
अवपत् ६. ६८, ३.
अवपत् ८. ८, ५; १९. ३६, ४.
अवऽपद्यते ६. १३६, ३.
अवऽपद्यन्ते ५. १७, ७.
अवऽपद्यमानाम् ५. १७, ४.
अवपन् १८. ४, ५५.
अवपन् ६. १०९, ३.
अवऽपश्यन् १. ३३, २.
अवऽपानम् २०. १७, २; ८७, १.
अवऽप्रभ्रंशनम् १९. ३९, ८.
अवऽभृथम् ९. ११, ५.
अवमम् ५. १३, २; १०. ७, ८.
अवमा १८. २, ४८.
अवमाः १९. ४७, ५.
अवमान् ६. १०३, २.
अवऽमुञ्चन् ८. २, २.
अवऽमुञ्चमानः ८. १, ४.
अवयत् १०. २, १३.
अवयन् १४. १, ४५.
अवऽयाः २. ३५, १.
अवऽयाता २. २, २.
अवऽयानम् ८. १, ६.
अवरः १८. २, ३२.
अवरऽपरम् ११. ३, २०.
अवरम् १. ८, ३; ५. ११, ५; ७. ३६, ३; ८. ३, ३; १०. ८, ८.
अवरा ७. ४२, १.
अवरान् १२. २, २९.
अवराय १. १२, ४.
अवऽरुन्द्धे ९. ९, २; ४; ६; ८.

अवऽरूढौ ६. १४०, १.
अवरे ५. २, ६; २४, १६; १०. ७, २१; १८. १, ४४; २०. ३४, ८; १०७, ९.
अवरे १. १७, २.
अवरेण ९. १४, १७; १८; १९, २९; १३. १, ४१.
अवऽरोचते ३. ७, ३.
अवर्चसम् ४. २२, ३.
अवर्जुषीणाम् ७. ५२, २.
अवर्तत ४. २, ७; १९. ६, ८; ५२, १; ५६, ३.
अवर्तयः २०. २९, ३.
अवर्तयत् २०. २७, ५.
अवर्तिः ४. ३४, ३; १०. २, १०; १२. ८, १०.
अवर्तिम् ९. २, ३; ४; ४, १७.
अवर्त्या १२. २, ३९.
अवर्धत २०. ३१, ३.
अवर्धत १५. १, ४.
अवर्धन्त ५. १९, १.
अवर्धयत् २०. २७, ५.
अवर्माणः ११. १२, २३.
अववृत्रन् ६. २२, १; ९. १९, २२; १२. २, २२; ४१; १३. ३, ९; २०. ८, ३.
अवशः ६. ४२, ३; ४३, ३.
अवशत् २०. ९५, १.
अवऽशसा ६. ४५, २.
अवशा३ १२. ४, ४२.
अवशाम् १२. ४, १७.
अवऽश्वसम् ४. ३७, ३.
अवऽसर्जनाय ६. ८४, १.
अवसा ५. २, ६; १८. १, ५१; २०. १०७, ९.
अवसानऽदर्शः ७. ४२, १.
अवऽसानम् १८. १, ५५; २, ३७; १९. १४, १.
अवऽसृष्टा १. ३, ९; ३. १९, ८.
अवऽसृष्टाः १७. १, २८.
अवऽसृष्टाम् १४. २, ५३; ५४; ५५; ५६; ५७; ५८.
अवसे ३. २०, ४; ५. २५, २; ६. १०८, २; ७. ६, २; ४१, १; ८. ७, २३; २४; २०. ३४, ९; ८०, २; ९२, १७; १०३, १; १०५, ५; १३९, १.
अवस्कवम् २. ३१, ४.
अवस्त १४. १, ५६.
अवस्थस्य ७. ९५, ३.
अवस्यवः २०. १४, १; २४, ९; ६२, १; ७२, २; ७५, १.
अवस्रन् १८. ३, २४.
अवस्वन्तः ३. २६, ६.
अवहत् २०. ७६, २.
अवऽहतः ६. १३४, २.
अवहन् ११. १०, ४; १४. २, १.
अवऽहार्य ७. ९९, ४; १६. ४, ३.
अवऽहितम् ४. १३, १.
अवाचीः १०. २, ११.
अवाचीनम् १०. ४, २५.
अवाचीनान् १३. १, ३०.
अवाट् १८. ३, ४२; ४, १.
अवात् ८. १, २१.
अवात्सीः १५. ११, २; ३.
अवादिरन् ११. ६, ६.
अवादिषम् ४. ६, २; ५. ७, ४.
अवादिषुः ४. १९, १३.
अवारयन्त १०. ३, २.
अवास्तुम् १२. ९, ७.

अविऽअनत् ५. २, २.
अविऽऋद्धिः १०. २, १०.
अविऽएष्यत् १२. ४, ९.
अविः ३. २९, १; २; ५. १९, २; १०. ८, ३१; १२. २, ५३.
अविक्षत ६. ५२, २.
अविऽचाचलत् ६. ८७, १; २.
अविऽचाचलाः १०. ८, ४.
अविऽछेदाय ९. ८, ८.
अविज्ञातऽगदा १२. ४, १६.
अविऽअनत् २०. १०७, ५.
अविता १९. १३, ८; २०. ३४, ६; ३७, १०; ५६, ५; ६३, २; १२४, ३; ५.
अवितारम् ७. ९१, १; २०. १४, २; ६२, २.
अवित्तेः १६. ६, १०.
अवित्सि १८. १, ४५.
अविदः २. १०, ७.
अविदत् २०. २१, १.
अविदन् २. ९, ४.
अविदन् २. ९, ४.
अविदन्त १८. २, ४७.
अविदम् ८. १, २०; २०. ९६, १०.
अविदम् ८. १, २०; २, ३; २०. ९६, १०.
अविदाम ८. ५, ११.
अविदाम १०. १, १९; १८. १, १५.
अविदुःऽतरासः १९. ५९, २.
अविदुषः ४. १८, २.
अविद्याः ११. १०, २३.
अविद्वांसः ६. ११५, १.
अविऽद्विषे १. ३४, ५.
अविऽद्वेषम् ३. ३०, १.
अविधत् ४. ३२, १.
अविधवाः १२. २, ३१; १८. ३, ५७.
अविनक् ११. ३, ४.
अविन्दः २०. ७०, १.
अविन्दः २०. १३७, १०; ११.
अविन्दत् १३. २, ३६; २०. ११, ४; १७, ८.
अविन्दत् २. २७, २; ५. १४, १; १७, ५; २०. १६, ९; ९१, १.
अविन्दत २०. २५, ४.
अविन्दन् १३. १, ४; ७.
अविम् ३. १७, ३; २९, ३; ४; ५; ५. १, ९; ८, ४; ६. ७१, १; ७. ५२, ५.
अविऽमतः ६. ३७, १.
अविऽमोकयम् ६. ६३, १.
अविऽराधयन्ती २. ३६, ४.
अविवेषीः २०. ३७, ५.
अविशत् १०. १०, ७; २५; ११. १०, ११; २३; ३०; १२. १, ५५; १५. १०, ५.
अविशन् ११. १०, १३; १८; १९; २०; २१; २२; २४; २५; २७; २९.
अविशन्त १०. ८, ३; २०. ९४, ६.
अविश्वऽविन्नाम् ९. १४, १०.
अविषत् २०. ५६, १.
अविषम् ८. २, १९.
अविष्टम् २०. १३९, ५.
अविष्यवः ३. २६, २; ११. २, २; २०. २२, २.
अविऽह्रुतम् ६. २६, १.
अवीनाम् १९. ४७, ६.
अवीरऽघ्नीः ६. ८३, २; १४. १, ३९.
अवीरऽहा १. १६, ४; ६. १४, ३.
अवीराम्ऽइव २०. १२६, ९.
अवीवरत ३. १३, ३.
अवीवरन् ६. ८५, १; १०. ३, ५.
अवीवृतन् ७. ५९, २.

अवीवृताम् १४. २, ३६.
अवी॑वृधः १३. ७, १९.
अवीवृधत् १. २९, ३.
अवीवृधन् २०. ६९, ६.
अवृक् १३. २, ९.
अवृकम् २०. १३९, १.
अवृकाः १८. १, ४४.
अवृके॑भिः २०. ३७, ७.
अवृणक् २०. २१, ९.
अवृणीत २. ५, ७; ९. ४, ५; १४. १, १५; १८. ३, ४१[2].
अवृ॑णीध्वम् ६. ७, ३.
अवृ॑णीमहि ७. १०२, १.
अवृणोत् २०. ११, ३.
अवृ॑तः २०. ६७, १.
अवृतन् ३. ३१, १.
अवृ॑श्चन् १२. ४, ५०.
अवृषत ३. ३, ५.
अवे॑त् १०. १०, २२.
अवेपन्त १०. १०, २३.
अवे॑पयः ५. २२, १०.
अवेपयः २०. ४२, ३.
अवेशयत् ११. ८, २३.
अवैरऽहत्याय॑ ६. २९, ३.
अवो॑चत् ५. २, ९; १७, ३; २०.१०७, १२.
अवोचम् ४. ६, ४; ९[2]; ५. ३०, ८; १६; ९. १३, १०; ११; १२; १९; २०.
अवोचाम ५. १, ९.
अव्य॑यम् २०. ५५, ३.
अव्य॑सः १९. ६८, १.
अव्या॑म् ५. ३१, २; १२. २, १९; २०.
अव्रतः ६. २०, १; ७. १२१, २.
अव्रा॑त्यः १५. १३, ११.
अश॑कत् १२. ४, १८.
अशकन् १. २७, ३.
अशत्रु ६. ४०, २.
अशत्रुः २०. ९५, ३.
अशत्रुऽभ्य॑ः २०. १३७, १०.
अशनऽकृत॑म् ९. ६, १३.
अशनानशने इत्य॑शनऽअनशने १९. ६, २.
अश॑निः ३. २७, ४; ६. ३७, २; १४२, १; ७. ५२, १; ८. ३, ४.
अश॑निऽभिः ८. ३, ६.
अश॑निम् ८. ४, २०; २५.
अश॑ने ५. २९, ६; ७.
अशन्या॑ ७. ११४, ४.
अशन्यै॑ १२. ३, ५८.
अश॑पतः ६. ३७, ३; ७. ६१, १.
अश॑म् २. २५, १.
अश॑यत् ११. १०, १६.
अशरीत् ६. ६६, २; ७५, १.
अश॑रैत् ६. ३२, २.
अश॑स्तयः ७. ११९, २.
अश॑स्तानि ६. ४५, १.
अश॑स्तिः १. २०, १; ५. ३, ६.
अश॑स्तिम् ८. २, २; १७. १, ८; १७.
अशस्तिऽहा २०. १०५, १.
अश॑स्त्याः १२. २, १२.
अशान १. ७, २.
अशायत २०. १७, ६.
अशिक्षन् ११. १०, १७.
अशितऽव॑ति ९. ८, ८.
अशिता १२. ८, १०; ११.
अशि॑वा २०. ७३, ६.
अशि॑वाः ७. ४४, १; १२. २, २७.
अशि॑वासः २०. ७९, २.

अशिश्रियत् ६. ३१, ३; २०. ४८, ६.

अशिषत् १९. ४९, १०.

अशिष्टान् २. ३१, ३.

अशीतर्यः ११. ३, २१.

अशीतिः ५. १९, ८; १९. ४७, ३.

अशीतिऽभिः २. १२, ४.

अशीमहि १९. ११, ६.

अशीमहि १३. १, ६०; १४. २, ५; १८. ३, ६७; १९. ४७, २[२]; २०. ७९, १.

अशीय १६. ४, ६; १९. ६१, १.

अशीर्षाणःऽइव ६. ६७, २.

अशीर्षाणम् १९. ४७, ८; ५०, १.

अशीशमः ९. १३, २२.

अशीशमत् २. ३, ४.

अशीशमन् ३. २१, १०.

अशीशमम् ३. २१, ९.

अशुनम् १४. २, १६.

अशृण्वन् १९. ५२, ३.

अशोणाः १९. ६०, १.

अश्नः ९. १४, १.

अश्नन्ति ९. ७, ८; ९; ११. १२, १४.

अश्नन्तु १२. ३, ३२.

अश्नवत् १९. ५५, ६.

अश्नवातै १२. ३, ३४.

अश्नवामहै ६. १०९, २.

अश्ना २०. १६, ८.

अश्नाति ९. ८, १; २; ३; ४; ५; ६.

अश्नाति ९. ८, १; २; ३; ४; ५; ६; १४. १, ३; ५.

अश्नामि ६. १३५, १; ७. १०६, १.

अश्नासि ८. २, १९.

अश्नीयात् ४. ११, ३.

अश्नीयात् ९. ७, ७[२]; ८, ७; ८; ९; १२. ४, ४३; ४४; ४६.

अश्नुतः १४. २, ९.

अश्नुतम् १४. १, २२.

अश्नुताम् ८. २, ८; १४. २, ६४.

अश्नुते १९. ३८, १.

अश्नुते ४. ९, ५; ११, ४; ९. ५, २६; १०. १०, ३३; १९. ३८, १.

अश्नुवन्ति २०. ७३, २.

अश्नुवे ९. १५, १९.

अश्नुहि २०. २२, १.

अश्मनः ६. ४२, २; २०. १६, ४.

अश्मना ५. २३, १३; ६. १३८, ५; ७. ३६, २; १३. १, ३२.

अश्मने १. १३, १.

अश्मनोः २०. ३४, ३.

अश्मन्ऽमयानि २०. ९१, ३.

अश्मन्ऽवती १२. २, २६; २७.

अश्मऽवर्म ५. १०, १; २; ३; ४; ५; ६; ७.

अश्मऽसु ३. २१, १; १२. १, १९.

अश्महन्मऽभिः ८. ४, ५.

अश्मा १. २६, १; २; १३, ४; ४. १२, ७; १०. ५, २०; १२. १, २६; १८. ४, ५४.

अश्मानः ४. १८. ३; ११. ९, २१.

अश्मानम् १. २, २; २. १३, ४; ७. ३६, ३; ८. ४, १९; १३. ७, १३; १४. १, ४७; २०. ७७, ६.

अश्यमाना १२. ८, १०.

अश्रद्धा ११. १०, २२.

अश्रद्धाः १२. २, ५१.

अश्रमत् ६. ६०, २.

अश्रयन् ११. १२, १०.

अश्रवन् ७. ६८, १.

अश्रवम् २०. १२६, ११.
अश्रांतम् ७. ७५, १.
अश्रान्तस्य १९. २५, १.
अश्रीरम् ४. २१, ६.
अश्रुऽमुखी ११. ११, ७.
अश्रूणि ५. १९, १३.
अश्रेष्माणः ३. ९, २.
अश्रैत् १३. २, ९.
अश्लीला १४. १, २७.
अश्लोणः १. ३१, ३.
अश्लोणाः ६. १२०, ३.
अश्वऽअभिधान्यां ४. ३६, १०; ५. १४, ६.
अश्वः २. ३०, ५; ५. ५, ८; ८. २, २५; ९. १४, २; १०. १०, १६; ११. ७, १८; १३. ३, १८; १९. ५३, १; २०. १०२, २.
अश्वःऽइव १०. १, १९; १२. १, ५७; २, ५०; १९. ५७, ४[२].
अश्वऽक्षभा १९. ४९, १.
अश्वऽजित् ५. ३, ११; ७. ५२, ८.
अश्वतरस्य ४. ४, ८.
अश्वतर्यः ८. ८, २२.
अश्वत्थ ३. ६, ५.
अश्वत्थ ३. ६, २; ३; ४; ६; ८. ८, ३.
अश्वत्थः ३. ६, १; ५. ४, ३; ६. ११, १; ९५, १; ८. ७, २०; १९. ३९, ६.
अश्वत्थस्य ३. ६, ८.
अश्वत्थाः ४. ३७, ४.
अश्वत्थात् ५. ५, ५.
अश्वऽपर्णाः ६. १२६, ३.
अश्वम् १. १६, ४; ४. ९, ७; ५. २९, १; ६. ७१, १; ८. ७, ११; १०. १, १७; २९; २०. १६, ११; २७, ३; ५५, ३; ९८, २.
अश्वम्ऽइव ४. ३६, १०; ५. १४, ६.
अश्वऽयन्तः २०. ९६, ५; १२१, २; १२५, ३.
अश्वऽयुजौ १९. ७, ५.
अश्वऽवत् १८. ३, ६१; २०. ७, ३.
अश्वऽवति २०. २५, १.
अश्वऽवती ३. १२, २.
अश्वऽवतीः ३. १६, ७.
अश्वऽवतीम् १८. २, ३१.
अश्वऽवत्या २०. २१, ९.
अश्वऽवन्तम् २०. २५, ४.
अश्वऽवान् ६. ६८, ३.
अश्वस्य ४. ४, ८; १५, ११; ५. ५, ९; ६. ३८, ४; ७२, ३; ९. १५, १३; १४; १०. ४, २; १९. ४९, ४; २०. २१, २; ४१, २; ११८, २; १३७, ३.
अश्वस्यऽइव ११. २, २२.
अश्वाऽइव ८. ४, ६.
अश्वाः १. ४, ४; २. २६, ३; ३. १६, ६; ९. १४, ३; ११. २, ९; ३, ५; १३. १, २४; २, ६; ७; १८. ४, १०; १९. २, ४; ६, १२; २०. १३, ४; ९४, ७.
अश्वाःऽइव १९. ३८, २.
अश्वान् ६. ७७, १.
अश्वानाम् ४. ९, २; ८. ४, १०; १२. १, ५; १९. ४७, ७.
अश्वायऽइव ३. १५, ८; १९. ५५, १; ६.
अश्वासः २०. ३४, ७.
अश्विना ५. २६, १२; ६. ५०, १; ६९, २; ९. १, १९; १४. १, ३६.
अश्विना ३. ३, ४; ४, ४; १६, १; २२, ४; ४. ३०, १; ५. ३, ९; २५, ३; ६. ३, ३; ८२, २; १०३, १; १४१, २; ७. ५५, १; ९. १२, १९; ११. ८, ४; १०, ५; १४.

१, ८; ९; २०; ३५; ५४; २, १३; १९. १०, ४; २०, १; ४०, ४; ४२, ४; २०. २१, ४; १२५, ५; १४२, २; ४.
अश्विना २. ३०, २; ६. ४, ३; १०२, १; १४१, ३; ७. ५४, १; ७७, १; २; ४; ५; ९. १, ११; १६; १७; १४. १, १४; ५५; २, ५; २०. १२५, ४; १३९, १; २; ३; ४; ५; १४०, ३; ४; ५; १४१, २; ४; १४२, ६; १४३, १; २; ३; ६; ९.
अश्विनी ७. ५१, २.
अश्विनोः २. २९, ६; ७. ७७, ३; ९. १, ११; ४, ८; १५; १९. ५१, २; २०. १४०, २; १४१, ३; १४२, १; ३.
अश्विनौ १०. ६, १२; १२. १, १०; १८. २, ३३; १९. १६, २; २७, १५; २०. १४१, ३.
अश्विऽभ्याम् ७. ७७, ८; ९. १५, ५.
अश्वेभिः ६. १०८, १.
अश्वेभ्यः ३. २८, ३; ९. ३, १३; १२. २, १६; १९. ४७, ९.
अश्वेषु ४. २२, २; ९. १, १८; १२. १, १९; २५; २, १५; २०. ७४, १; २; ३; ४; ५; ६; ७.
अश्वैः ३. १६, ३; ७. ८६, ४; ५; १८. १, २४; २०. १६, १२.
अश्व्यम् २०. १४, ४; ६२, ४.
अश्व्येन ८. ३, १५.
अषाढाः १९. ७, ४.
अषाळ्हम् २०. ९२, १९.
अष्ट ५. १५, ८; ८. ९, २१[2]; २३; ११. १०, २९.
अष्ट २०. ९२, २०.
अष्टऽऋचेभ्यः १९. २३, ५.
अष्टका १५. १६, २.
अष्टऽकृत्वः ११. २, ९.
अष्टऽधा १३. ३, १९.
अष्टऽपुत्रा ८. ९, २१.
अष्टमः १३. ५, ५.
अष्टमीम् ८. ९, २१.
अष्टये ६. ५४, १.
अष्टऽयोनिः ८. ९, २१.
अष्टऽवृषः ५. १६, ८.
अष्टाऽचक्रम् ११. ६, २२.
अष्टाऽचक्रा १०. २, ३१.
अष्टादशऽऋचेभ्यः १९. २३, १५.
अष्टाऽपक्षाम् ९. ३, २१.
अष्टाऽपदी ५. १९, ७; ९. १५, २१; १०. १, २४; १३. १, ४२.
अष्टाऽपदीम् २०. ४२, १.
अष्टाऽयोगैः ६. ९१, १.
अष्टाऽविंशानि १९. ८, २.
अष्टौ २. १२, ७; १९. ४७, ३.
अष्ट्राम् ३. १७, ६.
अष्ठीवत्ऽभ्याम् २. ३३, ५; ११. ४, १४[2]; २०. ९६, २१.
अष्ठीवन्तौ ९. ४, १२; १२, १०; १०. २, २; ९, २१; ११. १०, १४.
असंसूक्तऽगिलेभ्यः ११. २, ३०.
असः १. १६, ४; ३४, २; ५[2]; २. ३०, १[2]; ३. १७, ८; २५, ५; ४. १, ७; ८, ६; ६. ८, १[2]; २[2]; ३[2]; ९, २; ७. ३८, १; ३९, ४; ११८, १; ८. २, १३; १४. १, २०; ५०; २, ७५; १९. ४६, ७; २०. ९४, ४.
असः ३. १२, ५; ६. १३१, ३; १८. २, ३०.
असत् १. २२, २; २. २८, ५; ३. २०, ६; २३, ५; ४. १३, ४; १९, ६; ६. ७५,

३; ७. ४३, २; ९९, ३; ८. ४, १२[२]; १३; ९, २१; ७, २२; १०. ७, १०; २९; १६. ६, ११; १८. २, ३०; १९. ३१, २; २०. ७१, ११; ७६, २.
असत् १. २६, १; २. १, २; ३. १७, २; ६. ९, २; ७. ९८, ८; ९. १४, १९; १०. ४, १८; १४. २, १९; २१; १८. १, १२; १९. ४६, ७; २०. १९, २.
अस॑त १८. ४, ९९.
अस॑तः ४. १, १; ५. ६, १; ८. ४, ८; १०. ७, २९.
अस॑ति ६. ६४, ३; १११, १; ३; ७. ३७, १; १४. १, १८; १७. १, १९.
अस॑तीभ्यः ७. ८०, १.
अस॑त्ऽतराः ७. ८०, १.
असत्ऽमन्त्रात् ४. ९, ६.
असत्वम् १९. ४८, ३.
असत्ऽशाखाम् १०. ७, २१.
असदः १८. ४, ९२.
अस॑दत् ६. ३१, १; २०. ४८, ४.
अस॑दन् ७. १०१, १.
असदन् ६. ९२, २; २०. १७, ४.
अस॑न् ८. ४, ८; ११. १, १३; ९, ३; १२. २, २६; २७; २०. ७६, ४.
अस॑नत् २०. ९१, १०.
अस॑नम् १९. ३२, ७.
अस॑नाम १६. ६, १.
अस॑नाय १. १३, ४.
असनोत् २०. ११, १०[२].
असंतापे इत्यसम्ऽतापे ४. २६, ३; ८. २, १४.
अस॑पत्नः १. १९, ४.
असपत्नः १. २९, ५; १०. ६, ३०; १९. ४६, ७.
असपत्नम् ८. ५, १७[३]; ९. २, ७; ८; १२. १, ४१; १९. १६, १; २७, १४.
असपत्नाः १९. १४, १.
अस॑पर्यैत् १४. २, २०.
अस॑बन्धुः ६. १५, २; ५४, ३.
अस॑मः १२. ३, ३८.
अस॑मातिम् ६. ७९, १.
अस॑म्ऽऋद्धयः १४. २, ४९.
अस॑म्ऽऋद्धये ५. ७, १.
अस॑म्ऽऋद्धाः १. २७, २; ३.
असम्ऽऋद्धे ५. ७, ७.
अस॑म्ऽख्याताः १२. ३, २८.
असम्ऽख्येयम् १०. ८, २४.
अस॑म्ऽज्ञा १२. ८, ७.
असम्ऽतापम् १६. ३, ६.
असम्ऽबाधम् १२. १, २.
असम्ऽबाधे १८. २, २०.
असम्ऽभव्यम् ५. १८, १२; १९, ११.
अस॑म्ऽयत् १८. १, १४.
अस॑म्ऽयत्तः २०. २५, ३.
अस॑म्ऽस्थितम् ६. ५०, २.
असयः १०. १, २०.
असरन् २. १४, ६; ३. ३१, ३.
अस॑र्वऽवीरः ९. २, १४.
अस॑वः ८. २, २६; १८. ३, ६२.
अस॑वे १९. ४४, ४.
असश्चतः ५. ६, ३.
अस॑सि १. २९, ३; २. ३, १; ६. १११, २; ४; ७. ११८, २.
अस॑हन्त ११. १, २.
असहन्त ३. १०, १२.
अस॑हिष्ट २०. ८७, ५.
असा॑त् ६. १२८, १.

असाथ ३. ८, ४; १४. १, ३२.

असादयन् ११. १०, २८; २९.

असादाः ११. १२, २४.

असानि १. २९, ५; ३. ५, ५; ८, २; ६. ९७, १; ७. ३९, २; ८. ५, १९.

असानि १९. ३१, ६.

असाम १९. ४९, ६; २०. २१, ११.

असामि २०. ३०, ५.

असाविषुः १. १८, २.

असि १. २३, ३; २५, २; ३; ४. ९, १०; ३३, ६; ५. ५, २; ११, ९; १४, ७; १६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ६. ४६, १; ७. ३९, ५; ४८, १; ३; ९. ३, ९; १०. १, २९; १३. ७, १७; १७. १, २१; १८. १, ३८; १९. ३८, २; २०. २९, १; ५६, २[३]. ६०, १; ६४, २; ३; १०१, ३; १०४, ४; १११, ३; १२०, १.

असि १. १३, ३; २०, ४; २३, १; २५, २; ३; ३४, १; २. ३, २; ११, १[३]; २[३]; ४[३]; ५[४]; १७, १; २; ३; ४; ५; ६; ७; १८, १; २; ३; ४; ५; २७, १; ३. ५, ८; १०, १३; १२, ३; ५; १८, ५; २०, २; ४. ३, ७; ४, ५[२]; ६, ८; ७, ६; ९, १; २; ३[२]; १०, ६[२]; १२, १; १९, १[२]; २; ३[२]; २०, ३; ७; ३१, ४; ५. ४, ७[२]; ९; ५, १[२]; ३; ४; ६; ७; ८; ६, ४; ९; ११; १२; १३; १४; १०, १; २; ३; ४; ५; ६; ७; ११, २; ९; ११; १२, १; ३; १३, १०; ११; १६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २०, १०; २२, ५; २५, ७; ८; २९, १; ६. १५, १; १६, २; ४[२]; २१, २; ४४, ३[२]; ४६, १[२]; २[३]; ४८, १; २; ३; ८१, १; ८६, ३[२]; ९५, ३; ९८, ३[२]; १००, ३[२]; १०८, १; १२५, १; १२६, २; १३३, २[२]; १३६, १; १३८, १; ७. १३, २; ३९, ३; ८६, ३; ४[३]; ९३, १[२]; ९४, ४[३]; ११६, १; ११८, २[२]; ८. २, २८[२]; ५, ११; ९. २, १९; २०; २१; २२; २३[३]; २४; ३, ७; ५, १०; १६[२]; १०. ४, २४[२]; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४४; ८, २७; ११. १, ६; ३५; ६, १८; १२. १, ६१; १३. २, १९; २९[३]; ३०; ८, १; २; १४. १, ५१; २, १५; १६. १, ६; २, ६; ४, २; ५, १; २[२]; ४[३]; ५[३]; ६[३]; ७[३]; ८; ९[२]; १७. १, ११; १२; २०[३]; २१[२]; १८. १, १५; २२; ३, ५; ३६[३]; ३७[३]; ४, ६८; १९. ३१, ११; १२[३]; १३; ३२, ३; ५; ३४, १[२]; ३५, ३; ३९, ४; ९; ४४, १; ५; ४८, ६; ४९, ८; ५२, २; ५७, ३; ५९, १; २०. ११, २; १८, ६; २१, २; ३४, १८; ३७, १; ४७, १६; ५८, ३[२]; ४[२]; ६२, ६[२]; ७३, १; ८७, ६; ९२, ९; ९३, २; ५; ६; ८; ९५, ४; १०४, ४; १०५, १[२]; ११४, १; ११८, २; १२०, १.

असिक्नि १.२३, १.

असिक्नी १. २३, ३.

असिक्नीः ८. ७, १.

असिक्न्या ५. १३, ८.

असिक्न्याम् १२. २, २०.

असिचन् ४. ८, ६; २०. ७६, ७.

असिञ्चत् ६. १३२, ३;

असिञ्चत् १०. ७, २८;

असिञ्चत ११. १२, १२; १३;

असिञ्चताम् ६. १३२, ४; ५.

असिञ्चन् ६. १३२, १; २.
असितः ३. २७, १; ६. ७२, १.
असितऽज्ञूः १२. १, २१.
असितम् १. २३, ३[२]; ११. २, १८.
असितम् १०. ४, ५; १३.
असितस्य १. १४, ४; ६. १३७, १.
असितस्य ५. १३, ६.
असिताः ५. १३, ५.
असिताः ६. १३७, २; ३.
असितात् ७. ५८, १.
असिताय ६. ५६, २; १२. ३, ५५.
असिना ९. ५, ४.
असिम् २०. १२६, १८.
असिष्टौ ४. २८, २.
असिस्रसन् ७. ११२, १.
असीन् ११. ११, १.
असुः ५. १, ७; ६. ५३, २; ८. १, ३; ९. १४, ४.
असुऽतपा १९. ४९, ७.
असुऽतृपः ८. ३, १३; १०. ५, ४९.
असुऽतृपौ १८. २, १३.
असुतानाम् २०. ९३, ३.
असुना ६. १०४, १; ८. १, १.
असुऽनीताय १८. २, ५६.
असुऽनीतिः १८. ३, ५९.
असुऽनीतिम् १८. १, ३१; २, ५.
असुन्वत २०. ८९, ४.
असुन्वाम् २०. २९, ५.
असुम् २. १२, ८; ५. २९, ५; ३०, १; ७. २, १; ८. १, १५; २, १; १८. १, २९; ४४; २, १३.
असुर २०. ३२, १.
असुरः १. १०, १; ४. १५, १२; ५. २७, १; ८. ६, ५; १८. १, २३.
असुरऽक्षयणम् ११. १२, १०; १२; १३.
असुरऽक्षितिम् १०. ६, २२; २३; २४; २५; २६; २७; २८.
असुरऽघ्नः २०. ३६, ४.
असुरऽमायया ३. ९, ४.
असुरस्य ४. ८, ३; ६. ७२, १; १८. १, २; १९. ५६, १; २०. ९१, २.
असुराः २. ३, ३; ६. १०८, ३; १०९, ३; ८. १३, १; ४; १०. १०, २६; ११. १२, १५; १९. ६६, १.
असुराणाम् ४. २३, ५; ६. ७, ३; ८६, ३; १००, ३; १०. ३, २; ६, १०; १९. १३, १.
असुरान् ४. १९, ४; ६. ७, २; ८. ५, ३; ९, २४; १३, १; ९. २, १७; १८; १०. ३, ११; ११. ७, ७; १२. १, ५; २०. ६३, २; १२४, ५.
असुराय ५. ११, १; १३. ७, १४.
असुरेभ्यः २. २७, ३; ४; ६. ६५, ३; १९. ५६, ३; २०. ५५, २.
असुर्यः २०. ५८, ४.
असुर्याय २०. ७७, २.
असूतिका ६. ८३, ३.
असून् ६. १०४, १; १२. २, ५५; १८. २, २७.
असूतम् १०. ३, ९.
असूस्वः १०. १०, २३.
असृक् ४. १२, ४; ५; ९. १४, ४.
असृक्ऽपावानम् २. २५, ३.
असृक्ऽमुखान् ११. ११, १७.
असृक्षत २०. १२६, १.

असृक्षत १४. २, ५२; २०. ११९, १.
असृग्रम् २०. ७१, १०.
असृजः २०. ९, ४; ४९, ७.
असृजः २०. १५, ६; ९५, ३.
असृजत् १९. ५३, ६.
असृजत १२. २, १७.
असृजत ८. ५, १४; ११. ५, ४; १९. ५३, १०; २०. ९१, ८.
असृजन् २. १०, ८.
असृजन्त १. १३, ४; ३. २८, १.
असृपत् १९. ४४, ७.
असृष्ट १८. १, ३९.
असो इति १९. ४४, ४.
असौः ११. ९, १६; १८. २, २४.
असौ १. २६, १; २; २९, ५; २. १४, ३; ३. २, ६; ४. २, ३; ४; १६, ३; ५. ८, ३; ७; ६. १३०, १; २[२]; ३[२]; ४; १३१, १; २; ७. ७३, १; २; ११. १२, ११; १२. ३, २०; १३. १, २३; १५. १०, ७; १५, ४; ५; १८, २[२]; १६. ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१; १८. ४, ६६.
असौ ४. १६, ९; ५. ६, ५; ६; ७; १८. ४, ३३.
अस्कन्दत् १०. १०, १६.
अस्कभायत् ४. १, ४; ७. २७, १.
अस्कभायत् ४. १, ४; ९. १५, ३.
अस्कधोयुः २०. ३६, ३.
अस्तकम् २. २६, ५.
अस्तभ्नाः २०. ९३, ६.
अस्तभ्नात् ४. ३५, ३; १९. ३२, ९; २०. ३४, २.
अस्तम् ४. १५, ६; १०. ८, १६; १४. १, ४३; २, १३; २९; १८. ३, ५८; २०. १२६, २०; २१.
अस्तम्ऽइताय १७. १, २३.
अस्तम्ऽएष्यते १७. १, २३.
अस्तम्ऽयते १७. १, २३.
अस्तम्ऽयन् ९. १०, ५.
अस्तर्या ५. ३१, १२.
अस्तरीः १२. ३, ३८.
अस्ता ६. ९३,१; ८. ३, ५; १९. १३, ४; २०. ३५, ७; ९५, ४,
अस्ताऽइव १९. ३४, ३; २०. ८९, १.
अस्ताः १. १९, २.
अस्तानीत् ५. २०, २.
अस्ताम् ६. ५९, ३; १२. २, ४७; ४, ५२.
अस्तारम् २०. ७, १.
अस्ताविं २०. ११९, १.
अस्ति १. १८, ३; ४. १२, २; ५. ६, १२; १३; १४; ११, ६; ७. ५, ४; १०२, २; १०. ७, ३१; ११. १२, २७; १२. ३, ४८; १४. २, १२; १८. १, ३३; १९. ५, १; २०. ६५, १; ३; ८२, २; ११७, २; १२५, ३; १४१, ५.
अस्ति ३. ६, ७; ४. १९, २; ५. ६, ११; ११, ५; ७. ८, १; ५८, ६; ८. ९, २२; ९. २, १२; १४, १; ११. १, ३३; २, २५; १२. २, ३६; १९. ५३, ४; २०. २७, ४; ३४, ५; ९७, ३;
अस्तु १९. ७, २.
अस्तु १. १, २; ३; ३, १; २; ३; ४; ५; ९, २; १०, २; १२, ४[२]; १३, १[२]; ३;

४; २५, ४; २६, १; २; ३१, ४[२]; २. २, १; १०, २; ३५, ४; ३६, १; ४; ३. १०, २; ६; १४, ४; १५, १[२]; ४[२]; १६, ५; १९, १; ५; २१, १; २; ३; ४; ५; ६; ७; २७, १; २; ३; ४; ५; ६; ३०, ७; ४. २२, २; ३[२]; ३४, ८; ३८, ६; ५. ३, १; ३; ४; ५; ७, १; ३; २०, ७; २८, ६; २९, ६; ७; ८; ९; ३०, १२; ६. १२, ३; १३, १; १५, १; २०, १; २; २७, १; २; ३; २८, ३; २९, २; ३२, ३; ४०, १[३]; ५६, २; ५७, ३[२]; ६३, २[२]; ६४, ३; ६६, १; ६८, ३; ७१, ३; ७३, २; ३; ८४, ३; ९७, २; ९८, २; ११६, १; ३; १२८, २[२]; १४१, २; ७. ९, १; ४२, २; ८४, ४; ८५, ३; ८७, ३; ९२, १; १०६, १; १११, १; ८. १, १; १८; २, १; ७; १६; ४, ३; ८; ११[२]; ९. ४, २०; ५, १२; १०. १, ५; ३, २; ११. १, १५. २, ८; १५[२]; १८; २२; ६, ७[२]; ८; २३; १२, ४; १२. १, ११; ४२; २, ९; ३, ११[२]; ३२; ३९; ४, ४५; १३. १, १७; १८; १९; २७; ८, ३; ५; ६; ९, १; २; ४; १४. १, १९; ५२; ६०; २, ६३; १५. ११, २[३]; ६; ८; १०; १६. २, ६; १८. १, ४६; २, ३१; ३६[२]; ३, ६१; ७१; ४, १५; ४८; १९. ३, ४; ४, २[२]; ७, ३; ८, २; ३; ७[३]; ९, २[२]; ३; ४; ५; ९; १३[२]; १४; १०, २[२]; ३; ४; ५[२]; ६; ७; ९[२]; १०; ११, २; ३[२]; ६[२]; १४, १; १५, ३; ५; ४६, ५; ४९, ५; ५८, १; ६४, ३; २०. ४, ३[२]; ५, ४; १७, २; ३९, १; ४५, २; ७०, १६; ७१, १; ८९, ३; ९४, ९; १४३, ८.

अस्तृतः १९. ४६, १; २[२]; ३; ४; ५; ६; ७; २०. ४७, ३; १३७, १४.
अस्तृतः १. २०, ४; ५. ९, ७.
अस्तृतम् १९. ४६, १; २०. ६८, ४.
अस्तृते १९. ४६, ५.
अस्तृऽभिः २०. ७०, २०.
अस्तोषत १८. ४, ६१.
अस्तौत् २०. ९१, ३.
अस्त्रम् ११. १२, १६.
अस्त्रा ११. २, ७.
अस्त्रे ६. ९३, २.
अस्त्रैणाः ८. ६, १६.
अस्थन्ऽवन्तम् ९. १४, ४.
अस्थऽभिः २०. ४१, १.
अस्थात् २. ३४, २. ६. ४४, १[३]; ७७, १[३].
अस्थात् ९. १४, १७; १०. १०, १३; १३. १, ११; ४१; २, ३३; १९. १३, १०.
अस्थाम् १०. ५, ३६; १२. १, ११; १६. ९, १.
अस्थाम ३. ३१, ११.
अस्थि ४. १०, ७; १२, ३; ४; ५; १०. ९, १८; ११. १०, ११; २९.
अस्थिऽजस्य १. २३, ४.
अस्थित ७. २८, १.
अस्थिऽभूयान् ५. १८, १३.
अस्थिऽभ्यः २. ३३, ६; २०. ९६, २२.
अस्थिरन् ४. २५, ७.
अस्थिऽस्रंसम् ६. १४, १.
अस्थीनि ९. ५, २३; ११. १०, १२; १२. ११, ९.
अस्थुः १. १७, ३; ६. ४४, १.
अस्थुः ६. ७७, १; ७. १०१, १; २०. १२, ३.
अस्थ्नः ४. १२, १.
अस्नः ५. ५, ९; १९, ३.

अस्ना ५. ५, ८.

अस्पार्शम् ३. ११, २; २०. ९६, ७.

अस्पृक्षत् ६. १२४, २.

अस्पृशन् ५. १९, १.

अस्पृशन्त १४. २, ३२.

अस्फुरत् २०. ३४, १३.

असत् १. २, ३; ९, २; ४; १८, ४; १९, १; २; २०, २; २६, १; ३. ७, ७; ४. १७, ५; ६. २०, १; २६, ३; ४५, २; ७३, ३; ८४, ३; ९३, २; ९७, २; १२१, १[२]; १२४, ३; ७. २४, १; ४३, १; २[२]; ५५, १; ६२, ४; ६; ८२, ३; ८८, ३; ४[२]; ९७, १; १२०, २; ८. ७, १४; १०. १, १६; ५, २३; २४; ११. २, १९; २६; १२. १, ४९; ५०; ३, ४०; ४३; १३. १, ३१; १४. २, ४८; १६. १, १०; ११; १८. १, ४०; ४, ६९; ७०; १९. ३१; ११; ३३, ३; २०. २३, ८; ६७, २[२]; १२५, ७.

अस्मऽत्रा २०. ९४, ३.

असत्ऽसंखा ६. १२५, १.

अस्मद्य्रञ्चि: २०. ३७, १०.

अस्मभ्यम् १. १६, १; १८, २; २६, २; २. ६, ५; ३. ५, ३; ८, १; १२, ५; ४. १८, ६; ३१, ७; ५. ३१, ११; ६. ९२, ३; ११०, १; १२८, ३; ७. १५, ३; २५, १; ५२, ४; ८३, २; १२०, ३; ८. ४, १४; ९. २, ३; ४, ६; २२; ५, १२; १२. १, ६२; १४. १, ६२; १८. २, १३; ३, १४; ४, ६२; १९. ११, ६; २०. ७०, १२.

अस्मऽयुः २०. २३, ७; २४, १.

अस्माकं १. ७, ६; ३. २४, ४; ७. ८२, १.

अस्माकम् २. १२, २; ३; २६, ४; ५; ३१, ५; ३. १०, १३; ४. ३१, ५; ५. ३, ११; ६. १५, १; ९३, १; १२६, ३; ७. ४२, २; ५२, ४; १०. ५, ३६[२]; १२. ३, ५५; ५६; ५७; ५८; ५९; ६०; १६. ८, १[१०]; ५[१०]; ६[१०]; ७[१०]; ८[१०]; ९[१०]; १०[१०]; ११[१०]; १२[१०]; १३[१०]; १४[१०]; १५[१०]; १६[१०]; १७[१०]; १८[१०]; १९[१०]; २०[१०]; २१[१०]; २२[१०]; २३[१०]; २४[१०]; २५[१०]; २६[१०]; २७[१०]; २८[१०]; २९[१०]; ३०[१०]; ९, १[२]; १८. ४, ६८; १९. १३, ७; ८; ११[३]; ३४, १; ५७, ५; २०. ४, १; ३९, १; ६३, २; ७०, १६; ८५, ३; ९५, २; १११, २; १२४, ५.

अस्माकासः ४. ३३, ३.

अस्माकेन २०. १७, १०; ९४, १०.

अस्मात् ८. १, ४; ७, ५; ९. २, १७; १८; १२. ८, ११; १८. २, २८; ४, ४९.

अस्मान् १. १, ४; १९, ३; २१, २; २९, १; २. ११, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; ३५, ४; ३. १, ३; २, ६; २७, १; २; ३; ४; ५; ६; ४. १०, ५; १९, ५; ४०, १; २; ३; ४; ५; ६; ७; ८; ५. ६, ८; ९; १०; १४, २; ६. ६, १; १५, १; २; १९, ३; २७, ३; ४७, १; २; ५१, २; ५४, ३; ६६, १; ११६, ३; ७. १०, २; २८, १; ६८, १; ७९, २; ८६, ५; ६; ११४, ४[२]; ८. ४, २३; ५, ४; ९. २, २५; ४, ७; १०. १, ७; २१; ५, १५; १६; १७; १८; १९; २०; २१; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; १२. १, २५;

२, १२; ३३; **१६.** १, ५; ७, ५; **१८.** ३, ४५; ४, ८७; **१९.** ४, ४; १३, ११; २०, १; ३; ३५, ४; ४५, ५; ४९, ३; ५०, ४; ६; ५८, २; ६४, २; **२०.** १२, २; ३७, ९; ५६, ३; ७१, १२; ८१, २; ९२, २१.

अस्माभिः **६.** १२२, १; **१२.** ३, ४२.

अस्मासु **४.** ३२, ४; **५.** ६, ८; **६.** ८४, २; **७.** ५, २; ५४, १; ८१, २; ८७, १; **१०.** ५, ७; ८; ९; १०; ११; १२; १३; १४; **११.** ७, २५; **१२.** २, ४६; **१९.** ३, ३; ३१, ३; ४५, २; ५७, २; ४; ६४, ४; **२०.** ६७, २.

अस्मि **३.** १९, १; ४; **५.** ११, १०; **६.** ११७, १; १२३, ३; १३३, ३; **८.** ४, १४; १५; **९.** १५, १५.

अस्मि **१.** ७, ४; ३४, ४; **३.** १८, ५; **४.** ३२, ५; ६; ३६, ६; **५.** ९, ७; ११, ३; १०; **६.** ३९, ३; ५८, ३; १२३, ३; **७.** ८४, २; **८.** ४, १६; ९, २२; **११.** १, १९; **१२.** १, ५४[२]; ५८; **१४.** २, ७१[२]; **१६.** ३, ६; **१८.** १, १३; **१९.** ३२, ५; **२०.** १२६, ९.

अस्मिन् **१.** ९, १; ११, १; १५, २; २०, १; ३०, १; ३५, ३; **२.** २६, १; **३.** १४, ३; १८, ३; **४.** ४, ४; ८; १६, ३; २२, ३; **५.** ३, ८; २४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; २६, २; ३; ७; ८; ९; १०; ११; २८, ४; **६.** ४७, २; ८५, १; ११७, ३; **७.** ४४, १; ४९, १; ६०, २; १०२, १; **८.** ५, २१; ७, ११; **९.** १, ६; ४, २३; ५, २; ७; ११; १४, १७; **१०.** ३, ५; १९; २०; २३; २४; ४, ८; **१२.** २, १३; **१३.** १, ४१; ५, ८; **१४.** १, २१; २, ४८; ४९; **१५.** १२, ७; ११; **१८.** १, ४२; ५९; ३, २०; ६७; ४, ४६; **१९.** २७, १०; ४६, ५; **२०.** ११, ११; १२, ५; १३, १; १७, २; ४५, ३; ७७, २; ७९, १; ९४, ५; ९.

अस्मिन् **५.** १९, ३; **१०.** २, ११; १२[२]; १३[२]; १४[२]; १७[२]; १९; ३, १७; ८, २४; **११.** १०, १६; १७; ३२; **१२.** ३, ३; **१३.** ४, १३; **१९.** ४६, ५; **२०.** ५, ७; ७०, ५.

अस्मृति **७.** १११, १.

अस्मे इति **४.** २१, १; **५.** १, ३; **१८.** १, ३; ४२; ४, ४६; **१९.** ४०, ४; **२०.** १३, १; ७१, १३; १४; ८९, ६; ७; ९४, ५; ११९, २[२]; १४३, ६; ७.

अस्मै **२०.** १३९, १.

अस्मै **१.** ३०, ३; ४; **२.** २९, १; २[३]; ५; **३.** ८, ४; १७, ५; २८, ३; **४.** २२, २; ४; ३१, ३; **५.** ३, ३; ४, ७; २६, ९; ३०, १२; **६.** ४०, २; ५४, २[२]; ८०, २; **७.** ८३, २; १०२, ३; **८.** २, ६; ८; ५, १०; ७, ६; २३; २४; २७; **१०.** ५, ७; ८; ९; १०; ११; १२; १३; १४; **१२.** २, ४५; **१४.** १, ३३[२]; २, २४; ३१; **१८.** १, ५५; ४, ३४; **१९.** ३०, २; ३८, २; ५५, १; **२०.** १५, ३; ३५, १; २; ३; ४; ५; ६; ८; १२; १५.

अस्मै **२.** ५, ६; २८, ५; २९, ५[२]; **३.** ३, २; **४.** ६, ३; २२, १; **५.** १, ९; १४, ४; १७, १७; १९, १५; **६.** ७८, १; १२३, २; १२८, १; **७.** १५, ३[२]; १९,

२; **८.** २, ५; १०; ११, ९; **९.** ५, २४; २५; २६; **१०.** २, १५^{२}; ५, ५०; ६, ६; ७; ८; ९; १०; ११; १३; १५; **११.** २, ८; १८; २२; **१२.** ४, १८; १९; ३५^{२}; **१८.** १, १०; ५५; २, १२; १९^{२}; ३७; ३, ५०; ५१; **१९.** ४१, १; ५२, ३; **२०.** २१, १०; २७, २; ३१, १; ३४, ५; १४; ३७, २; ७६, ७; ८; ८९, १; ५; ६; ९५, २; ९६, ३^{२}; ४.

अ॒स्य **१.** ९, २; ३२, २; **२.** ५, २; **४.** ४, ६; २२, २; २८, १; २; ३; ४; ५; ६; **५.** १२, ११; २३, २; २७, १०; २९, २; ३; ४; **६.** २८, ३; ३१, २; ३४, ५; ४८, १; २; ३; ५२, ३; ५४, १; ६८, ३; ७३, १; १०१, २; **७.** ९४, २; १००, १; **९.** १, १५; १४, १; ५; १५, १०; **१०.** ५, ४७; ८, ९; **११.** ६, २३; २४; **१३.** ३, २४; **१८.** १, ५; ७; ४८; ४, ८९; **१९.** ४९, ५; **२०.** ५, ५; १५, ५; १८, ४; ३५, ७; ९; १०; ११; १३; १४; ४८, ५; ६१, २; ६८, ८; ७२, ३; ७५, २; ३; ९६, १; ९९, २; १०१, १; १२१, १.

अ॒स्य॒ **१.** २, १; १२, २; ३; **२.** १, २; ९, ३; ३२, २; ५; **३.** ७, २; ११, ६; **४.** १, १; ३; ६; २, १; ११, ४^{२}; ५; ८; १२; १४, ८^{२}; १६, ४; ५; २१, २; २२, १; ३; २४, १; ३०, ७; ३४, १^{३}; **५.** ६, १; ८, ३; ४; १३, ३; १७, १२; १४; १५; १६; १८; १८, ६^{२}; २२, ५^{२}; २३, ९; १२; २७, १; ५; ७; २९, ५; १०; १२; १५; ३०, १३; **६.** ३, २; ६, २; १४, २; २०, १; ७६, ३; १३४, १; १३८, २; ३; **७.** १५, ४; १६, १; २१, ३; २७, ४; ४७, १; ४९, २; ५८, ५; ५९, २^{३}; ७३, १; २^{२}; ९५, २; १००, १; ३; **८.** ४, ११; १०, ५; ९; ११; १३; १२, २; ८; १५, ४; **९.** १, २३; ४, ४; ७; १६; ५, २३; २४; १४, १; ५; १८; **१०.** २, ५^{२}; ८; १५^{२}; २६; ३, १६; ४, ७; ५, ५०; ७, १^{४}; २; ३; ९; ८, ७; ८; १२; १३; १८; २४; ९, ४; **११.** २, २८; ३, ७^{२}; ८; २२; ६, २२; २५; १०, ३१; **१२.** ३, १८; ४५; ४, ३; १३; २७^{२}; ३८; ९, ४; ५; ११, ७^{२}; ८^{२}; ९^{२}; १०; **१३.** २, १; १४; १८; ३२; ३८; ४५; ३, १४; **१५.** १, ७; ३, ११; ५, ३; १६; १२, ६; ७; १०; ११; १३, १४; १५, ३; ४; ५; ६; ७; ८; ९; १६, १; २; ३; ४; ५; ६; ७; १७, १; २; ३; ४; ५; ६; ७; १८, २^{२}; ३^{२}; **१८.** १, ५; ३३; ३६; २, ४; ३, ७१; ४, ३४; ४४; **१९.** ६, २; ३^{३}; ५; ६^{२}; १०; १५; ३२, २; ५३, २; **२०.** ८, ३; ९, ४; ११, ६; ७; १३, ३; १७, ७; २४, २; २६, ५; ३०, ३; ३१, २; ३४, १४; ३५, ८; ३६, ३; ४७, ११; १५; ४९, ७; ५१, २; ४; ५५, २; ५८, २; ५९, ३; ६०, ४; ६; ६७, ६; ६९, १०; ७०, १३; ७१, ४; ६; ७३, ४; ६; ७६, ५; ७७, १; ५; ८१, १; ८७, २; ५; ८८, २; ८९, ६; ९२, १४; ९६, ४; ९७, २; ३; ९९, २; १०४, २; १०७, १; २; १०९, २; ३^{२}; १२३, २; १२६, ४; ५.

अ॒स्य॒त॒ः **१२.** ४, १७.

अ॒स्य॒त॒म् **३.** २५, ६; **८.** ४, २५.

अ॒स्य॒ता॒त् **१०.** ४, ६.

अ॒स्य॒ता॒म् **६.** ८९, ३; **१०.** १, २३.

अस्यति १३. ७, १३.
अस्यते ६. ९०, ३.
अस्यते ५. १९, ५; १३. २, ४३.
अस्यथ १. २६, १; ६. ६५, २.
अस्यन् २०. ८९, १.
अस्यन्तः ६. ६६, २.
अस्यन्तम् ११. २, १७,
अस्यन्ति ५. १८, ९.
अस्यन्ति १२. ३, २९.
अस्यसि १. १३, १; ११. २, २५.
अस्याः ५. १२, ४; २५, १०; ११; १२; १३; ६. ६०, २; ७. ९, १; १३, ३; १०८, १; ८. ६, ९; १५; ९. १५, १५; १२. ३, ४०; १४. १, ४८; २, २५; ६८; ६९; २०. ७२, ३; ७६, २.
अस्याः १. १४, १; ५. १७, ३; १७; १९, ५[२]; ७. २१, ५; ८. ६, ५; ९, १०[३]; ९. १, २; ३; ६; ७; १५, २३; १०. १०, ५; २३; २४; ३१; १२. ४, ५; ६; ७; ८; ९; १५; १८[२]; २७; २८; १४. १, १०; २६; ५७; २, २; १८. ४, ३२; २०. १२६, ११.
अस्याम् ३. २६, १; २; ३; ४; ५; ६; ५. २४, १[६]; २[६]; ३[६]; ४[६]; ५[६]; ६[६]; ७[६]; ८[६]; ९[६]; १०[६]; ११[६]; १२[६]; १३[६]; १४[६]; १५[६]; १६[६]; १७[६]; १९. ४७, २; २०. ३७, ७.
अस्याम् ३. १०, ४; ८. ९, ११; १०. १०, ३; ३३; १२. ७, २; ३; १४. २, १४.
अस्यामसि ६. ४२, २.
अस्यामि ५. ८, ५; ६. ३७, ३.
अस्यै २. ३६, १; ६. ६०, १; ३; ११. १, ३; ११; १२. ३, ११; १४. १, ३१; ५९; २, ९; १३; २१; २७; २८; २९; ७३; ७४; १५. १३, १३.
अस्यै २. ३६, ८; ३. २५, ६; ४. ५, ६; ६. ७८, ३; ८१, ३; ८. ६, ३; १४. १, ३९.
अस्रवन्तीम् ७. ७, १.
अस्रामः १. ३१, ३.
अस्राष्ट्रम् ४. २८, ४.
अस्वगता १२. ९, २.
अस्वगताम् ९. २, ३.
अस्वगम् १२. ९, ७.
अस्वप्नः ५. ३०, १०; ८. १, १३.
अस्वप्नाः १२. १, ७.
अस्वप्नेन १९. ५६, ५.
अस्व[म् ७. ३६, ३.
अस्वरन् ५. ६, ३; २०. १०, २; ५४, २; ५९, २; ९९, १.
अस्वापयः २०. ३७, ४.
अर्ह १. ३४, २; ४. १८, ७; ७. ३९, ४; १९. २, ४[२]; २०. १७, ६; ४०, ३; ४१, ३; ६९, १२; ८९, ८; १२६, २.
अर्हः २. १५, २; ४. १, ५; ६. ३१, ३; ८. ५, ६; १८; ९. २, १०; १०. २, १६; ११. ६, २१; १३. २, २२; ७, १; १५. २, ५; १३; १९; २०; २५; १७. १, २५; २६; १९. २०, ४; ४८, २; ५०, ७; २०. ४७, १९; ४८, ६.
अर्हःऽअहः १६. ७, ११; १९. ५५, ६; २०. ६६, ३.
अर्हःऽजातस्य ३. १४, १; ५. २८, १२.
अर्हःऽदिवि ५. २१, ६.
अर्हःऽभिः १८. १, ५५.
अर्हतः १२. १, ११.

अह॑न् **२**. ५, ५; ६; ७; **२०**. ११, ३; १६, ११; ३७, ५; ९१, १२; ९५, ३.

अ॒ह॒न् **८**. ५, ३; **२०**. ३७, ५; ७७, ७.

अह॑नि **७**. ५४, २.

अह॑नी॒ इति॑ **१३**. २, ३.

अह॑ऽभिः **१८**. १, १०.

अ॒हम् **१**. ९, ४; १०, ३; २९, ५; ६; **२**. १०, २; ३; ४; ५; ६; ७; ८; २५, २; २७, ५; ३०, ५^{२}; ३२, ३; **३**. ५, २; ५; ६, १; ३; ५; ७, ६; ८, ३; ६; १५, १; १८, ४; ५; १९, २^{२}; ३; ५; २२, ६; २४, १; २; २९, ८; ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; **४**. ४, ७; ५, ७; ६, ४; ५; ९, ७; १४, ३^{२}; १८, ५; २०, २; ४; ८; २६, ३; २८, ३; ३०, १^{५}; २; ३; ५^{३}; ६^{३}; ७; ८; ३२, ५; ३६, ७; ९; **५**. ३, ४; ७, ५; ७; ८, ८; ९; ९, ७; ११, ३^{२}; १०; १३, ३; ६; २३, १०; ३०, ८; **६**. १५, २; ३; २१, १; २३, १; ३९, ३; ५८, ३; ६१, २^{४}; ३^{३}; ६५, २; ७१, १; ७६, २; ८४, १; ९४, २; ९७, १; १०१, ३; १०२, २; १०८, २; ११७, २; ११९, १; १२२, ५; १२४, १; १२७, २; १३०, ३; १३३, ३^{२}; **७**. १३, ३; १६, १; ३६, २; ३९, २; ४; ५०, १; ५२, १; ७८, १; ३; ८४, २; १००, २; १०५, १; ११५, २; ११९, १; **८**. २, ३; ६; ४, १४; ७, ६; १८; ८, ८; ९, २२; **९**. २, २; ३, २; १५; १३, १०; ११; १२; १९; २०; **१०**. १, ४; ३२; ३, १०; ४, २१; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ३६; ७, ४३; ८, १६; ३८^{२}; ९, २७; १०, ३^{२}; **११**. १, १९; २७; ३, ३०; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ११, ४; १२, ९; १३; **१२**. १, ११; १२; ५४; २, ३२^{२}; ३३; ३, ४७^{२}; **१३**. १, १९; ३८; २, ४४; ४५; **१४**. १, ३८; ५१; ५७; २, १९; ७१^{३}; **१६**. ३, १; ४, १; ७, ८; **१७**. १, ६; २०; २१; २४; २७; २८; २९^{२}; **१८**. १, १३; ४५; ३, ५२; **१९**. ९, १४; ३१, ४; ५; ६; १३; ३२, ४; ५; ७; ३६, ६; ४०, २; ५१, १^{२}; ७०, १; **२०**. २७, १; २; ४२, १; ८२, १; ११५, १^{२}; २; १२६, ९; ११; १२; १४; १४१, ३; १४२, १.

अ॒ह॒म्ऽउ॒त्त॒रे **१२**. ४, ५०.

अ॒ह॒म्ऽउ॒त्त॒रेषु॑ **४**. २२, १.

अह॑यः **६**. ६७, २; **१०**. ४, ९.

अह॑ये **८**. ४, ९.

अह॑रत् **१०**. १०, ११.

अ॒ह॒र॒त् **१०** १०, १०; १२.

अह॑रितः **१**. २२, २.

अह॑र्यत् **२०**. ३१, ५.

अ॒ह॒र्य॑थाः **२०**. ३०, ५.

अहा॑ **१८**. १, ३१; **२०**. ८५, ३.

अहा॑ऽइव **५**. १, १.

अहा॑ः **२**. १०, ७.

अ॒हाः **६**. १०३, २; ३; **७**. ५५, ३; **१३**. १, ४.

अहा॑नि **७**. ७२, १; ८७, ४; ५; **१२**. २, २५; **१८**. १, २७; २८; **१९**. ७, १; **२०**. ११, ४; १०;

अ॒हा॒र्षम् **२**. २६, ५; **३**. ११, ३; ४; **६**. ८७, १; **८**. १, २०; २, १५; ७, २८; **१९**. ६४, १; **२०**. ९६, ८; ९; १०.

अहार्षीत् १३. १, ९.
अहासत २०. ७१, १०.
अहिंसतीम् ९. ३, २२.
अहिंसन्तः ६. ५०, २; १२. ३, ३१.
अहिंसन्तीः ९. १३, १३; १४; १५; १६; १७; १८.
अहिः ४. ९, ८; ६. ५६, १; १०. ४, २६; १९. ११, ३.
अहिऽघ्न्यः १०. ४, ७.
अहित ३. ११, ८.
अहिम् २. ५, ५; ६; ४. ३, ४; २४, ६; ६. १३९, ५; ७. ९३, १; १०. ४, ९; १०[२]; १६; १७; १९. ४७, ८; ५०, १; २०. ७, २; ३०, ४; ३४, ३; ११; ९१, १२; ९५, ३.
अहिऽहत्ये २०. ३५, ८.
अही इति १०. ४, ८.
अहीन् १०. ४, ६.
अहीनाम् २. ५, ७; ६. १२, १; १०. ४, १; ३; ४; २०; २३.
अहुतऽअदः १. ३०,४; १८. २, २८.
अहुतम् ६. ७१, २.
अहुतम् १५. १२, १०.
अहुताम् १२. ४, ५३.
अहुतेभ्यः ७. १०२, ७.
अहुवे २०. ६७, ७.
अहूमहि २०. ६४, ६.
अहृणीयमानः ५. १७, २; ६. ७४, ३; १८. ४, ६.
अहृणीयमानाः १. ३५, ४; ६. ७४, ३; ८. २, २१.
अहे ५. १३, ४; १०. ४, २१.
अहे ६. ५६, ३; १०. ४, १८.
अहेः १०. ४, १९; २६.
अहोता ९. ११, ४.
अहोरात्रयोः १५. ६, १८; १६. ८, २४.
अहोरात्राः ४. ३५, ४.
अहोरात्राभ्याम् ६. १२८, ३; १३. २, ४३; १४. २, ४०; १९. ८, २; ७.
अहोरात्रे इति १०. ७, ६; ८, २३; ११. ७, २०; ८, ५; ७; ९, १४; १२. १, ९; ३६; ५२; २, ४९; १३. २, ५; ३२; १५. ६, १७; १८, ४.
अहोरात्रैः १३. ३, ८.
अहौ ३. १३, १.
अह्नः ८. ९, ६; १३. ७, १; १६. ४, ४; १८. १, ७; २०. ८९, ५.
अह्ना ४. १८, १; १५. १८, ५; २०. ७७, ३.
अह्नाम् ३. १६, ४; ५. १२, ४; ६. १२८, २; ७. ८५, ४; ८६, २; १४. १, २४; १८. ४, ५८; २०. ११; ४.
अह्नि ६. ११०, ३; १९. ५६, २.
अह्ने ८. २, २०; १९. ४८, २; ५०, ७.
अह्नोः १६. ८, २५.
अह्यम् ४. १, २.
अहुतः ६. ९२, ३.
अहुताः ६. १२०, ३.
अह्वत् ३. ४, ५; ६.
अह्वम् १८. २, २३.
अह्वयत् १०. १०, १०; २२.
अह्वयन् ५. १, ८.
अह्वयन्त ८. ११, ३; १३, १; ५; ९; १३; १४, १; ५; ९; १३.
अह्वयेथाम् ४. २, ३.
अह्वि ४. १७, २.
अह्वे ४. २७, १; ६. ८०, २.

आ

आ **१.** १, २; २,२; ७, १; ४; ५; ६; ७; ८,
१; २; ९, ३; ४; १०, ४; १४, १; ३;
१५, २^{२}; २३, २; ३१, ३; **२.** २, ३; ५,
१; ४^{४}; ७; ६, १; ९, २; १०, ५; १२,
४; ५^{३}; ८; १३, ४^{२}; २५, ४; २६, १; २^{२};
५^{३}; २९, १; २; ४; ७; ३०, ५^{३}; ३५, ५;
३६, १; ५; ६; ८; **३.** १, ६; ३, १; २;
३; ४; ४, १; ५^{२}; ५, १; ४; ५; ८, १; ४;
६^{२}; ९, ३; १०, ७^{३}; ८; ११, २; ३; ४;
१२, ३^{३}; ७^{४}; १३, १; ५; ६; ७; १४, ४;
१५, १; ६; १६, ६; १७, २; २०, १;
१०; २२, ४; २३, २^{२}; ५; २४, १; ७;
२५, ५; २९, ७; ३०, ५; ३१, ११; **४.**
४, ६; ७; ८, १; २; ३; ९, १; ११, १;
४; १३, २^{२}; ३; ५^{२}; १४, ३^{२}; ४; १५,
६; ११^{२}; १४; १७, १; १९, १; ८;
२०, १; ३; ४; ६; २१, १; ३; २२,
२; ६; ७; २३, २; २४, १; २५, ५;
३०, ५^{२}; ३१, ३; ३२, ३; ५; ६^{२};
३३, १; ३४, ५; ३७, ६; ३८, ३;
५; ६; **५.** १, २^{३}; ३; ४; २, ४; ६;
७; ३, ५; ४, १; ६; ५, ३; ५; ९; ७,
१; ६; ८, १; २; ३; ७; ९; ११, ८; ९;
१२, १; ३; ६; ८^{२}; १३, ५; १४, ४;
१७, २; १२; १९, ८; २०, ४; २१,
१०^{२}; २२, ११; २५, १; २; ३; ५; ७;
८^{२}; ९; १०; ११; १२; १३; २९, ६; १२^{२};
२७, ८; ९; २८, १२^{३}; १४; २९, ५^{२};
१२; १३; ३०, ७; १३^{३}; ३१, १०; **६.** २,
१; २, २; ७, १; ११, १; १६, १; २२,
१; २६, १; २८, २; २९, ३^{२}; ३१, १;
३३, १; २; ३; ३५, १; २; ३; ३८, १;
२; ३; ४; ४८, १; २; ३; ५०, ३; ५१,
२; ५२, ३; ५३, २^{२}; ५५, २^{२}; ६०, १;
६१, १; ६२, २; ३; ६३, ४^{२}; ६५,
१; ६७, ३; ६८, १^{२}; ७३, १^{२}; ७६, २;
७७, ३; ७८, १; ७९, २^{२}; ८१, २^{२}; ३;
८२, २; ८७, १; ९२, १; ३; ९४, २^{२};
१०१, १; २; ३; १०२, २; १०४, १;
२; ३; १०८, १; ३; ५; ११०, १; ११७,
३; ११८, २; १२६, २^{२}; १३३, ४;
१३५, १; १३७, १; ३; **७.** १, २; ५,
२^{२}; ७, १; ९, १; १०, १; ४; १३, ३;
४; १४, १; २; १५, ३; १६, १; २१, ५;
२३, १; २७, २; ८; ३०, १; ४०, १;
४१, २; ४२, १; ५१, २; ५५, ३^{३}; ६;
५७, २; ५९, १; ६०, २; ६१, १; ६२,
१; ७; ६९, १; ७७, २; ४; ६; ९; १०;
७८, २; ७९, २; ८०, १; ४; ८१, २;
८४, २; ३^{२}; ८६, ५^{२}; ६; ८७, ४; ५; ६;
८९, ३; ९०, १; ९४, १; १०२, ४;
११५, ३; ११९, १^{४}; १२०, १; १२२, १;
८. १, ६^{२}; ८^{४}; ९; १६; २०^{२}; २, १^{२};
२; ७; १४; ३, १; २; ८; १६; ४, ९; ५,
२०; ७, ४; ७; १०; २६; ८, २; १८;
९, ६; १३^{२}; २२; ११, ४^{४}; १२, १; ३;
५; ७; १३, १^{२}; ५^{२}; ९^{२}; १३^{२}; १४, १^{२};
५^{२}; ९^{२}; १३^{२}; **९.** १, १४; २, ७; ११;
३, ३; १०; २१; ४, १; ७; ९; २२; ५,
१^{३}; ३^{२}; ५; ९; ३२; ३३; ३४; ३५; ३६;
७, ३; ११, १; १४, ८; १३; १५; २२;
१५, ८; १०; ११^{२}; १२; २२; २३^{२}; **१०.**
२, ५; ७; १७; २८; ३३; ३, १; २; ४,
६; १५; २२; २४; ५, ४२; ४६; ६, २;
२२; २३; २४; २५; २६; २७; २८; ७,

३५; ८, ३; २१[२]; ४०; ९, ५; १०, ११;
१२; **११.** १, ४; १०; १३; १४[२]; १५;
२०; २६; २९; ३२; २, २७; ६, ११; ७,
९; ११; १३; १९; ८, १८; ९, १४; १०,
४; १२[२]; १३; १६; १७; १८; २९; ११,
३; ११; १२, ३; १०; १६; **१२.** १, २०;
२९; ४०; ५५; ६१; २, १[२]; ६; १०;
१२; १७; २२[२]; २४; २८; ३०[२]; ३१;
४१; ४२; ४३; ४६; ४८; ५०; ५२; ३,
७; १३; १४; १५; १७; २०[२]; २२; २६;
३१; ३३; ४५; ४८; ५५; ५६; ५७; ५८;
५९; ६०; ४, ६; १२; १६; १९; २६;
३४; ५१; ७, ४; १०, ५; १०; ११, २;
१३. १, २[३]; ३; ४[२]; ५; १०[२]; १४; १५[४];
२०; २४; २६; ३०; ३३; ४५; ४६; २,
८; ९; १०; १९; २५[२]; ३३; ३५; ३९;
३, ९; २२; ४, ७; **१४.** १, ४; १२; २०;
२१; २५; ३९; ४७; ६१; ६२; २, ५;
८; १३; १४; १६; १९; २१; २२; २४;
३०; ३१; ३६; ३८; ३९; ४०[२]; ४८;
७०; ७१; ७३; **१५.** १, ६; २, ३; ८[२];
११; १४[२]; १७; २०[२]; २३; २८[२]; ३, ९;
७, ३[२]; ५[४]; १०, २[२]; ८; १०; ११, ७;
९; ११; १२, ६; १०; **१६.** १, १३; ४,
२; **१७.** १, ८; ११; २५; २६; ३०; **१८.**
१, १; ३; ८; ११; २१; २३; २४; २५;
२७; २८; ३७; ४२; ४५; ४६; ५१;
५६; ५७; ५९[२]; ६०[२]; ६१[२]; २, ३; २१;
२६; ३४; ५७; ६०; ३, २; १४; १९;
२३; ३०; ३१; ३२; ३३; ३४; ३५; ३८;
४१; ४४; ४५; ४७; ४८; ५७; ५८;
६२[२]; ६४; ६५; ६७; ७१; ७३; ४, १[२];
६[२]; १२; १४; १६; १७; १८; १९; २०;

२१; २२; २३; २४; ३७; ४६; ४८;
४९[२]; ५०; ५१; ५२; ५३; ६२; ६३;
६४; ६७; ८८[२]; ८९; **१९.** २, ५; ३, १;
२; ४, ३; ७, ४; ५[४]; १३, ५; १४, १;
१९, १; २; ३; ४; ५; ६; ७; ८; ९;
१०; ११; २२, २१; २३, ३०; ३१, ७;
९; १०; ३२, २; ३३, २; ५; ३४, ९;
३५, ३; ३७, १; २; ३९, १; ४२, ३;
४४, १०; ४५, ५[२]; ४७, १[२]; ४९, १; ३;
४; ५०, ७; ५१, २; ५२, २; ३; ४[२];
५३, १; ४; ५६, १; २; ५८, ५; ५९,
१[२]; २; ३; ६४, १; ३; ६५, १[२]; **२०.**
३, १[२]; २; ४, १; २; ५, ५; ७; ६, २;
८; ९; ७, ४; ८, २[२]; ३; ११, १[२]; ५;
१२, १; १३, १; २[२]; ४[२]; १४, ४; १५,
३; ५; १६, ५[२]; १७, ४; ८; १८, २;
१९, १; २०, २; ४[२]; २१, ३; २२, २;
५; २३, १; ३; २४, १; २; २५, ४; ५[२];
२६, २; २७, ६; ३०, १; २; ३; ३१, ५;
३२, १; २; ३; ३४, ५; १८[२]; ३५, ९;
१६; ३६, ३; ८; १०; ११[३]; ३८, १[२];
२; ५; ६; ४३, १; २; ३; ४४, ३; ४७,
५; ६; ७[२]; ८; १६; ४८, ४; ५०, २;
५२, २; ३; ५३, २; ३; ५५, १; २;
५६, ४; ६; ५७, २; ३; ५; ७[२]; १२;
१३; १५; १६; ५९, ४; ६१, ४; ६२, ४;
८; ६३, ६; ६४, १; ४; ६७, ४; ५; ६;
६८, २; ३; ४; ७; ११[२]; ६९, १[२]; ५;
७०, ५; ८; ९; १७; १९; ७१, ७; ८; ९;
१६; ७२, ३; ७३, ४; ७४, १; २; ३;
४; ५; ६; ७; ७६, २; ३; ४; ७[२]; ८[२];
७७, १; ५; ८; ७९, १; ८०, १[२]; ८१,
२; ८२, २; ८४, १; २; ३; ८५, ४;

८७, ३; ८८, ३; ८९, २; ३; ९०, १; ९१, ४; ६; १०; ९२, २; ७; १३; २१; ९३, ८; ९४, १; २; ३^{२}; ४; ५^{३}; ९६, २; ७; ८; ९; १०^{२}; २४; ९७, १; २^{२}; १०१, ३; १०३, २^{२}; १०४, ३; ४; १०७, ७; ९; १०; १४; १०८, १^{२}; ११३, १; ११७, ३; ११८, २; १२०, २^{२}; १२२, २; ३^{२}; १२४, १; १२६, २०; २१; १३७, २; १३९, १; १४०, २^{२}; ३^{२}; १४१, ४; १४२, १; ३; १४३, ३; ५.

आऽअंक्ता **१०.** १, २५.

आऽअक्षियन् **१२.** १, ५७.

आऽअगन् **६.** ११६, २; ३; **९.** १५, १५; **१८.** २, ३७.

आऽअच्यं **१८.** १, ५२.

आऽअर्जन्या **३.** २५, ५.

आऽअञ्जन **४.** ९, ३; ४; ५; ६; ७; १०; **१९.** ४४, १; १०; ४५, १.

आऽअञ्जनम् **४.** ९, ९; **१९.** ४४, २; ३; ४५, ३; ४.

आऽअञ्जनस्य **४.** ९, ८; **६.** १०२, ३.

आऽअञ्जनेन **१२.** २, ३१; **१८.** ३, ५७.

आऽअर्दिषि **७.** ५८, ५.

आऽअपृणात् **४.** ३५, ३.

आऽअवध्नन् **१.** ३५, १.

आऽअभरत् **११.** १०, ११.

आऽअभरन् **४.** २३, ६.

आऽअयति **४.** ३, ५; **६.** ६०, २; ७५, २; ३; **१९.** ४९, ९.

आऽअयनेन **६.** १२२, २.

आऽअंयसि **६.** १३०, ३.

आऽअवहः **७.** १०२, ३.

आऽअवहत् **११.** १०, १.

आऽअवांक्षुः **६.** ७८, १.

आऽअसिञ्चन् **६.** १००, २.

आऽअस्थात् **१३.** २, २८.

आऽइतः **६.** २९, २.

आऽइत्यं **१.** ७, ४; **१०.** ६, ५; **१९.** ५८, ६.

आऽइयर्थ **१०.** १, २४; २८.

आऽईमसि **१०.** ४, ६.

आऽईरिरे **२०.** ४०, ३; ६९, १२.

आऽउंतम् **११.** ९, १०.

आऽउंता **५.** २३, १; **६.** ९४, ३.

आऽउंताः **६.** २३, २; **१०.** ८, ३७; ३८.

आऽउंतौ **५.** २३, १; **६.** ९४, ३.

आऽउत्सूर्यम् **४.** ५, ७.

आऽउप्यमाना: **१२.** ३, २८.

आऽएति **३.** २, ६; **९.** १, २.

आऽएतोः **१२.** ३, ५५; ५६; ५७; ५८; ५९; ६०.

आः **१४.** १, ६^{२}.

आऽकिरन्तीम् **४.** ३८, २.

आऽकूतयः **३.** २, ४.

आऽकूतये **६.** ४१, १.

आऽकूतिः **४.** ३६, ४; **५.** ३, ४; **६.** ६४, ३; ७३, २; **११.** ९, १८.

आकूतिऽप्रः **३.** २९, २.

आऽकूतिम् **५.** ७, ८; ८, २; **११.** १०, ४; **१९.** ४, २; ४.

आऽकूतीः **३.** ८, ५; २०, ९; **६.** ९४, १.

आऽकूते **६.** १३१, २.

आऽकूत्या **३.** २, ३; **५.** ६, १०; **१९.** ४, ३^{२}.

आऽकूत्याम् **५.** २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.

आऽकृतिः १४. १, ४.
आऽकृत्य १०. १, ६.
आऽक्रंस्यमानः ९. ५, ८.
आऽक्रन्दः १२. १, ४१.
आऽक्रमणम् ९. ३०, ७; १३. १, ४४.
आऽक्रम्य ८. ८, १६.
आऽक्षियति १०. ५, ४५.
आऽक्षियन्ति १८. २, ४९.
आखण्डल २०. ५, ६.
आऽखरः २. ३६, ४.
आऽखरे ६. ४९, ३.
आखुम् ६. ५०, १.
आगः. ४. १३, १; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; १८. १, ५२.
आऽगच्छतः ६. ८२, १.
आऽगच्छेत् १५. १०, १; ११, १; १२, २; १३, ११.
आऽगतम् १०. ४, ९.
आऽगतस्य ६. ८२, १.
आऽगताः १४. २, १०.
आऽगते ७. ५४, २; ११. ६, ४; १९. १३, १.
आऽगतेन १९. ५३, ७.
आऽगत्य २०. २४, ७.
आऽगमत् २०. २४, ४.
आऽगमिष्ठाः १८. १, ४५.
आऽगमे ६. ८१, २.
आऽगरे ४. ३६. ३.
आगसः १२. ४, ५०.
आग्नीध्रात् २०. २, २; ६७, ५.
आऽघाटाः ४. ३७, ५.
आघृणिः ७. १०, २.
आऽघोषते २०. २९, ६.
आऽघ्नानाः ११. ११, १४; १२. १०, २.
आङ्गिरसः ६. ४५, ३; ८. १३, १५; १०. १, ६; ११. १२, १०; १२; १३; १९. ४, ४; २०. १६, २; ९०, १.
आङ्गिरसम् ५. १९, २.
आङ्गिरसानाम् १६. ८, १५; १९. २२, १.
आङ्गिरसि १२. १०, ६.
आङ्गिरसीः ८. ५, ९; ७, १७; २४; ११. ६. १६.
आङ्क्षम् २०. ३५, २; ३.
आऽचरन्तम् २. ३४, ५.
आऽचरन्ती ७. ७७, ११; ९. १५, २०.
आऽचरन्तीः २०. १३७, ९.
आऽचरिक्रत् ११. ७, ६.
आऽचार्यः ११. ७, ३; ८; १४; १५; १६; १७.
आऽचार्यम् ११. ७, १.
आऽचार्याय १९. ६४, ४.
आऽचितम् ४. ७, ५; २०, १२६, १८.
आऽचुच्युवीमहि २०. १४०, ४.
आच्छत्ऽविधानैः १४. १, ५.
आऽजगन्थ १४. २, १९.
आऽजगाम ६. २७, १; ७१, २.
आऽजग्म ७. १०२, ४.
आऽजग्मुषः २. २६, २.
आजत् २०. १६, ५; ७; २५, ५; २८, २; ३९, ३; ८८, ५.
आजत १२. ४, २४.
आजऽमीळ्हासः २०. १४३, ६.
आजयः २०. ५६, ३.

आजिम् ६. ९२, २; ७. ८७, १; १३. २, ४; ५; २०. ८७, ४.
आजिषु २०. ५६, १.
आजीन् २. १४, ६.
आऽजुहोति ९. ४, ९; १८.
आऽजुह्वानः ५. १२, ३.
आऽजुह्वानस्य २०. ६७, ३.
आजौ २०. १६, २; १३७, ८.
आज्यम् ५. ८, १; ६. ११९, ३; ७. ७३, २; ३; ९. २, ८; ४, ७; ५, ३८; ६, ११; १०. ६, ६; ११. ७, १३; १०, २९; १२. ४, ३४; १३. १, ५३; १९. ६, १०.
आज्यस्य १. ७, २.
आज्यानि ६. ११४, ३; ८. ९, १८.
आज्याय ११. १, ३१.
आज्ये ५. २१, २; ११. ११, ६.
आज्येन २. २६, ४; ५. २१, ३; ९. २, १; १०. ९, २५; १२. ३, २३; १३. १, ५२; १९. २७, ५.
आञ्जनऽअभ्यञ्जनम् ९. ६, ११.
आण्डऽअदः ८. ६, २५.
आण्डाऽइव २०. १६, ७.
आण्डात् १४. २, ४४.
आण्डीकम् ५. १७, १६.
आण्डौ ९. १२, १३.
आण्ड्यौ ६. १३८, २.
आत् २. ३, २; ३. १३, २; ६; २१, १०; ४. ३, ३; ४; ९, ८; २०, १; ५. १३, २; ३; ६. २२, १; ७. ७३, २; ८. ६, २६; ९. १५, १५; २२; १०. १०, १०; ११. ७, २४; ११, ८; १३. २, ४१; २०. २५, ४; ४०, ३; ६३, ३; ६९, १२; ७५, ३; ११४, २; १२३, १; १२४, ६; १२६, १३; १८.
आऽततः १३. १, ६०; १८. ४, ५९.
आऽततम् ७. २७, ७; ९५, ३.
आऽतनोति १२. १, १५.
आऽतन्वानाः ६. ६६, २.
आऽतपन्तम् ८. ६, १२.
आऽतपन्ति १२. ३, ५०.
आऽतस्थतुः ७. ११५, २.
आतस्थिऽवांसा २०. ३४, ८.
आऽतस्थुः ९. १४, ११; १४.
आऽतिष्ठन्तः ५. १, ४.
आऽतिष्ठन्तम् ४. ८, ३.
आऽतिष्ठ २. १, ४.
आऽतुतोद १८. ३, ५५.
आतुरम् ६. १०१, २.
आऽतृदः १४. २, ४७.
आऽतोदिनौ ७. १००, ३.
आत्मऽदाः ४. २, १; १३. ३, २४.
आत्मऽदूषिः १६. १, ३.
आत्मन् ९. ७, ४; १२. ३, ५४; १५. १, २.
आत्मनः ५. २९, ५; ९. १३, ९; ११. ७, १५; १५. १०, २.
आत्मना ३. २९, ८; ५. २९, ६; ७; ८; ९; ८. २, ८; ९. ५, ३१; ३२; ३३; ३४; ३५; ३६; १८. २, ७; १९. ३३, ५.
आत्मनि १. १८, ३; ४. १२, २; ७. ५५, ३; ५९, १; ९. १, ११; १२; १३; १६.
आत्मने ४. १८, ६; १२. १, १०; २, ३४.
आत्मन्ऽवत् ४. १०, ७; २५, १; १०. २, ३२; ८, २; ४३; ११. २, १०; १३. १, ५२.
आत्मन्ऽवताम् १९. २७, ८.

आत्मन्ऽवती १४. २, १४.
आत्मऽपराजितः ५. १८, २.
आत्मऽसदौ ५. ९, ८.
आत्मऽसु ३. १५, ७; ११. ७, २२; १९. ४८, ५.
आत्मा ५. १, ७; ५, ७; ९, ७; ६. ५३, २; ७. ६९, १; ११६, १; ९. ४, १०; १४, ४; १३. २, ३५; १६. ३, ५; ७, ५; १९. ५१, १; ६०, २; २०. १०७, १४.
आत्मानम् ४. ९, ७; २०, ५; ५. ९, ७; ६. १६, २; ८. ६, १३; ९. ५, ३०; १०. ८, ४४; ११. १०, ३१; १२. ३, ३०; ५१; ४, ३०; १६. ७, ५; १९. १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
आत्म्यः १९. ३९, ९.
आथर्वण ६. १, १.
आथर्वणम् ४. ३, ७.
आथर्वणाः १०. ६, २०.
आथर्वणानाम् १६. ८, १७; १९. २३, १.
आथर्वणीः ११. ६, १६.
आर्दत् २०. १६, ६; ३४, ४.
आऽदत्ते १२. ९, ८.
आऽददानः १८. २, ५९; ६०.
आऽददानम् १२. १०, ६.
आऽददानस्य १२. ५, ५; ६, ५.
आऽददाना ४. ३८, ३.
आऽददे ७. १४, १; १३. ३, ५.
आऽदधे १. २८, ३; ४. १७, ३; ५. २५, २; ६. १७, १.
आऽदभुः २०. ८३, २.
आऽदहनम् १२. १०, २.
आऽदानम् ६. १०४, २; ३.
आदानऽसंदानाभ्याम् ११. ११, ३.

आऽदानेन ६. १०४, १.
आऽदाय १२. २, ३५; १०, ११.
आदित्य ५. २१, १०; ११. १२, ४; १७. १, २५.
आदित्य ७. ८८, ३; ९. १३, २२; १३. २, ३; २८; २९[२]; १८. ४, ६९; २०. ५८, ३.
आदित्यः २. ३२, १; ४. ३९, ६; ६. ५२, १; ९. २, १५; ११. ११, २५; १२, ११; १६; १५. ४, १८; १०, ७; १५, ४; १८, २; १७. १, २४; १९. ९, १०.
आदित्यम् ३. २०, ४; १०. ८, १७; १५. ४, १७; १०, ११; १७, ९.
आदित्यऽवन्तम् १९. १८, ४.
आदित्यस्य १३. २, १.
आदित्याः ६. ११४, १.
आदित्याः १. ९, १; ३. २७, १; ५. ३, ९; १०; ६. ६८, १; ७४, ३; ८. १, १६; १०. ७, २२; ९, ८; ११. ८, १३; १२. २, ६; ३, ४३; १४. १, १; २; १५. २, २; १८. ३, १२; ४, ३; १९. ९, ११; ११, ४; १६, २; २७, १५.
आदित्याः १. ३०, १; ५. २८, ४; ६. ११४, २.
आदित्यान् ३. ८, ३; १०. ९, १०; ११. ८, ५; १३. ३, १७.
आदित्यानाम् ९. १, ४; ४, १३; १५. २, ४; १८. ४, ८; १९. १३, १०.
आदित्याय ४. ३९, ५[२]; १२. ३, ५५.
आदित्यासः १९. ५६, ४.
आदित्ये १०. ३, १८.
आदित्येन ४. ३९, ६.
आदित्येभिः २. १२, ४; १९. १०, ६; २०. १४१, २.

आदित्येभ्यः १२. ३, ४४; १५. २, ३; १९. ३९, ५.
आदित्यैः ४. ३०, १; ८. ८, १२; १०. १०, ९; १८. ३, २७; १९. १७, ४; २०. ६३, १; २; १२४, ४; ५.
आदित्यौ ८. २, १५.
आऽदिदेशति ६. ६, २.
आऽदिद्योत ६. २४, २.
आदिनवम् ७. ११४, ४.
आऽदीयमाना १२. ७, ४.
आद्यम् ८. २, १९.
आद्यैः १९. २२, १.
आऽधार्य ८. ६, १३; १३. १, ४७.
आऽधारः १२. ३, ४८.
आऽधिः ५. १७, ३.
आधिऽपत्यम् १८, ४, ५४; १९. ५६, ३.
आधीऽपर्णाम् ३. २५, २.
आऽधृषे ६. ३३, २[2].
आऽध्यः ६. १३१, १.
आध्या ६. १३२, १; २; ३; ४; ५.
आध्रः ३. १६, २.
आध्वम् ४. १४, २.
आन ९. १५, ९.
आनंशं ६. ४९, १.
आनंश २०. ६४, ५.
आनट् १८. ३, ६५; २०. ७६, ८; ९१, ७.
आऽनन्दः ९. १२, २३.
आऽनन्दाः ११. ९, २६; १०, २४.
आऽनन्दान् १०. २, ९.
आऽनन्दिनीः ४. १५, १६.
आऽनन्दिनीम् ४. ३८, ४.
आनवे २०. १२०, १.
आनशानाः २. १, ५; ६. ४७, ३; १९. ५६, ३.
आनशुः २०. ३६, ४; ५०, १.
आनशुः ९. १५, १; २०. १०, २; ५९, २.
आनशे ६. ११३, १; ३.
आनशे १३. १, १६; २०. ३१, ३.
आऽनिनाय २०. १४, ३; ६२, ३.
आनिषुः ३. १३, ४.
आनुषक् ४. ३२, १; २०. २३, २; १४२, २.
आनृचुः १२. १, ३९.
आनृचुः २०. ११९, २.
आऽनृत्यतः ४. ३७, ७.
आनृधुः २. ३५, १.
आऽनोनवीति २०. १६, १२.
आन्तरिक्षाः १९. ९, ७.
आत्रम् १०. ९, १६.
आत्राणि ९. १२, १६; १३, १७; ११. ३, १०.
आत्रेभ्यः २. ३३, ४; १०. १०, २१; २०. ९६, २०.
आत्रेषु १. ३, ६.
आप ८. ९, २०; १२. ३, ५.
आपः १. ५, १; ३; ६, १; ३; ४[2]; २५, १; ३३, १; २; ३; ४; २. ५, ६; ७, १; २३, १; २; ३; ४; ५; २९, ५; ३. ७, ५[3]; १२, ९; १३, ५[3]; २१, १०; २६, ३; ३१, ३; ४. २, ६; ८; ८, ४; ५; ६; १५, १; ५; ९; ११; ५. १७, १; २८, २; ६. २३, २; २४, १; २; ५१, २; ५८, २; ६१, १; ६८, २; ८५, ३; ९१, ३[3]; १२४, २; ७. १९, २; ४१, १; ६६, १; ८८, २; ११२, १; ११७, १; ८. १, ५; २, १४; ७, ३; ९. १, ९[2]; २, २०; ३, २२; २३; ६, ५; १६; १०. २, ११; १६; ५, २२; २३; ६, ३; १४; ७, ६; १०; ११; ३७; १०, ४; २९; ११. १, १७; २, २४; ७, १३; ८,

२३; ९, २; २०; १०, २९; ३०; १२. १, ३; ९; १९; २३; ३०; ५३; २, ४०; ३, ४; १३. १, ४५; ३, ६; ७, ९; १४. १, ३९; ४०[२]; २, १६; ४५; १५. २, १६; ७, २; ३; १५, ७; १६. १, १०; १८. १, १७; ३, ११; ४, ३९[२]; ४०; १९. २, १[२]; २[२]; ३; ९, १; १४; १०, ८; १७, ६; २७, ३; ९; ४०, २; ४३, ७; ४४, १; ९; ५४, १; २०. १२, ४; १५, २; १७, ७; २५, १; २; ५२, १; ५७, १४; ७१, ३; ९२, ८; १०६, २; १४३, ८.

आपः १. ३३, ४; ३. १३, २; ७; ७. ९४, ३; १०. ५, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; १२. ३, १३; २७; २९; १६. १, ८; १२; ४, ६;

आपःऽइव ८. ४, ८; ११. २, ८.

आपत् १. ३०, १; ११. १, २२; १४. २, ६९[४]; १७. १, २९; १९. २०, ४.

आऽपतन्तम् १२. २, ४७.

आऽपद्य ११. १, ३०.

आपन् १७. १, २८.

आपम् १२. ३, ४५.

आपाकेऽस्थाः ८. ६, १४.

आपिऽत्वम् २०. ११४, १.

आपिथ १३. २, ३०.

आऽपीतासः २०. १४२, ४.

आऽपीनाम् ९. १, ९.

आपुः ४. ३५, ४.

आपुः ९. २, १९; १२. ३, २८; १७. १, १२.

आऽपूर्णः २०. ८, ३.

आऽपृणासि १३. १, ९; १८. २, ९.

आपेः ४. ३२, ६.

आपेयम् ३. २०, ९.

आप्तः २०. १२२, २.

आप्तम् ५. २, ७; २०. १०७, १०.

आप्त्यानाम् ५. २, ७; २०. १०७, १०

आप्त्ये १९. ५६, ४; २०. १११, १.

आप्नुहि २. ११, १; २; ३; ४; ५.

आप्नोत् ३. १३, २.

आप्नोति ९. ५, २२; ११, १३[२].

आप्नोति ४. ९, ५; ११, ९; ९. २, २४; ५, १४; १०. २, २०; २१; ९, ६; १०; १३. २, १५.

आप्नोतु ४. ३८, ३.

आप्य॑म् २०. ८२, २.

आऽप्यायमानाः १८. ३, १७.

आऽप्याययन्ति ७. ८६, ६.

आऽप्रयच्छ ७. २७, ८.

आप्रियः ११. ९, १९.

आऽप्रुषायन् २०. १६, ४.

आऽवधे ५. २८, ११.

आऽवबन्ध ६. ६३, १; १३३, १.

आऽवभूथ ४. ३१, ५.

आऽवभूव ५. १, १.

आऽवभूवुः १०. ४, २३.

आवयो इति ६. १६, १.

आवयो इति ६. १६, १.

आऽवेधुः ९. ३, ६.

आऽवेधे ५. २८, ११.

आऽभंगः २०. ९४, ९.

आऽभंगम् ४. २३, ३.

आऽभरन्तीम् ८. ९, १४.

आऽभर्वन् ३. २९, २.

आऽभाति १३. २, २.

आभिः २०. ३६, १.

आभिः २. २, ३; २०. ३६, ११.
आऽभुवम् २०. ६७, १².
आभूकम् ६. २९, ३.
आऽभूतः ११. ६, २०.
आऽभूत्या ४. ३१, ६.
आऽभूषति ७. १२, १.
आऽभूषन्तः २०. ९६, ५.
आऽभृतः २. ४, ५; ४. १०, ४; ९. ४, १०; २०. ६७, ६.
आऽभृतम् ६. १२५, २; ७. ४६, १; १०. १, १९; ११. ७, १४; २२; १३. १, ५५; ४, २; ३; ४; ५; ६; ७; ९.
आऽभृताः १. ६, ४; ८. ५, ९; ७, ८; २५; १९. २, २.
आऽभृताभ्यः ८. ७, १५.
आभृते इत्याऽभृते १०. २, १.
आभ्यः ३. ३, ३;
आभ्यः ६. ५१, २; १४१, १; १०. ६, १४; १७.
आमऽअदः ८. ३, ७; ११. १२, ८.
आऽमनसम् २. ३६, ६.
आऽमत्रणम् ८. १०, १३.
आऽमत्रणीयः ८. १०, १३.
आऽमत्रणे ८. १०, १२.
आमऽपात्रम् ८. १४, १०.
आमम् ८. ६, २३.
आममत् ६. ५७, ३; १०. ५, २३.
आमयत् २०. १२६, २३.
आमयत् ९. १३, १०.
आमिक्षा ९. ४, ४.
आमिक्षाम् १०. ९, १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४.
आमित्रः ४. २१, ३.
आमित्री ५. २०, ५; ११. १२, २५.
आऽमुरिम् २०. ५४, १.
आमुष्यायण ४. १६, ९.
आमुष्यायणम् १०. ५, ४४; १६. ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१.
आमुष्यायणस्य १०. ५, ३६.
आमुष्यायणे १६. ७, ८.
आमे ४. १७, ४²; ५. २९, ६; ३१, १².
आर्य १९. ८, ३.
आऽयच्छन्तः ६. ६६, २.
आऽयत् १२. ३, ४९.
आऽयतः ६. ८२, १; ७. ३९, १; ६२, २; ३.
आऽयतनम् १५. १२, ७; ११.
आऽयता ६. ६५, १.
आऽयताम् ११. २, १.
आऽयतायाम् ६. ३८, ४.
आऽयतीः ६. १०९, २; १९. ५८, ३.
आऽयतीम् १३. २, ४६.
आऽयते ११. २, १५; ६, ७.
आऽयत्ताः ११. ९, ३.
आयत्ऽवसुः १३. ९, ३.
आयन् ३. २२, ३; ५. २८, ८; १८. १, ३१; २०. ६३, २; १२४, ५.
आयन् ४. १४, १; ८. ९, १८; १०. ८, ३; ११. ७, २.
आऽयन् ७. ८६, २; १४. १, २४.
आयने ६. १०६, १.
आऽयन्तम् ७. १४, २.
आऽयन्ति ६. ६६, १; १०३, ३; १२. ४, ११.
आयम् २. १, ४; ५.

आयवः **२०.** १०, २; ५९, २; ७२, १[२]; ९९, १; २.

आऽयवनम् **९.** ६, १७; **११.** ३, १६; **१२.** ३, ३६.

आयवे **२०.** ६१, २.

आयसः **२०.** ३०, ३; ४; ३१, ३.

आयसीः **१९.** ५८, ४.

आयुः **१.** ३०, ३; ३५, २; **२.** १३, २; ४; १७, ४[२]; २९, २; **४.** ३९, २; ४; ६; ८; **५.** ९, ८; **६.** ४१, ३; ७८, ३; **७.** ३३, १; ३४, १; ५५, ३; ६; ८६, २; ८७, २; १०८, १; **८.** १, ३; २०; २, १; २; ७; ११; १७; ४, १५; **९.** ४, २२; **१०.** २, १५; ५, ३६; **११.** १, ३४; ६, ६; **१२.** १, २२; ६२; २, २४[२]; ३०; ४५; ४, २८; ६, ३; **१३.** २, ३७; **१४.** १, २२; २४; ४७; २, ३६; ३९; ६४; ७५; **१६.** ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; **१८.** २, ३; १०; २३; २९; ४६; ५५; ३, १७; ४, ४८; ५३; ६२; **१९.** २४, ४; ३२, ३; ५५, ६; ५६, ५; ६१, १; ६३, १; ६४, ४; ६९, १; २; ३; ४; ७०, १; ७१, १; **२०.** १२, २; २१, ११; ९६, १०.

आयुःऽकृत् **५.** ९, ८.

आयुःऽकृताम् **३.** ३१, ८; **१९.** २७, ८.

आयुःऽददम् **६.** ५२, ३.

आयुःऽदाः **२.** १३, १.

आयुःऽप्रतरणः **४.** १०, ४.

आऽयुजः **११.** १०, २५.

आयुधम् **६.** १३३, २; **१०.** १०, १८; **११.** ११, १; **२०.** १३८, ३.

आयुधा **३.** १९, ५; **४.** ३१, १; **५.** २, ५; **२०.** १०७, ८.

आयुधानि **५.** २०, ८; **८.** ८, २०; **२०.** ३५, १३.

आयुम् **२०.** २१, १०.

आऽयुयुत्रे **२०.** ९४, ७.

आयुषः **१०.** ३, १६; **१९.** ४४, १; ५८, १.

आयुषा **३.** ५, ३; ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०[३]; ११; **७.** ९४, २; **९.** १, १५; **१०.** ५, ४७; **१२.** २, ३२; ५५; **१३.** १, १७; १८; १९; **१४.** २, २; **१९.** २७, ८; ३३, १.

आयुषे **१.** ३५, १; **२.** २८, ५; **४.** १०, ७; **५.** २८, ६; १३; **६.** ६३, १; ७६, २; ४; **१८.** २, २३; **१९.** २४, २; ३; २६, ३; ३२, १; ४०, ३; ४५, ६; ७; ८; ९; १०; ४६, १.

आयुष्पत्नी इत्यायुःऽपत्नी **५.** ९, ८.

आयुष्मत् **६.** ९८, २.

आयुष्मतः **८.** २, १३.

आयुष्मताम् **३.** ३१, ८.

आयुष्मती **१४.** १, ४५.

आयुष्मतीम् **३.** १०, ३; ८.

आयुष्मन्तः **६.** ४७, १; २; **७.** ६३, १; २.

आयुष्मान् **८.** ५, १९; २१; **१०.** ३, १०; १२; **१७.** १, १; **१८.** २, ४५; **१९.** २६, २; २७, ८.

आयुष्यम् **२.** २९, १; **१९.** २६, ४.

आयूंषि **२.** ४, ६; **४.** १०, ६; **५.** २८, ७; **६.** ७८, ३; **७.** १५, ४; **१२.** २, १३;

२५; **१४**. २, ६७; **१९**. ३४, ४; **२०**. १३७, ३.

आयोः **५**. १, ६; **१८**. ३, २३.

आरं **४**. २७, ६.

आरण्याः **५**. २१, ४; **६**. ५०, ३; **११**. २, २४; ७, २१; ८, ८; **१२**. १, ४९; **१९**. ६, १४.

आरण्यैः **३**. ३१, ३.

आरत् **१०**. ४, १.

आरत **२०**. ६८, ५.

आऽरब्धः **५**. १८, ४.

आऽरब्धान् **८**. ३, ७.

आऽरभमाणा **४**. ३०, ८.

आऽरभ्य **२०**. १५, ४.

आरात् **१**. १९, १; **२**. ३, ६; **६**. ३०, २; ३२, १; **७**. ९७, १; **८**. १, १२; २, ९; १२; **९**. १५, २५; **१०**. १, १; २; **१९**. ३१, ११; ५६, ६; **२०**. ८९, ६; ७; १२५, ७.

आऽरुजन्तः **४**. ३१, १.

आरुजत्नुऽभिः **२०**. ७०, १.

आऽरुजासि **२०**. ९४, ९.

आऽरुजे **२०**. १२४, २.

आऽरुरुक्षतः **२०**. २९, ४.

आऽरुरुहुः **४**. ११, ६.

आऽरुहः **१३**. १, ९.

आऽरुहम् **२०**. ९४, ६.

आऽरुह्य **८**. ५, ७.

आऽरुरोज **४**. २४, २.

आऽरूढः **६**. ११, १.

आरे **१**. २६, १[2]; **६**. ४५, २; **१०**. ४, २६; **२०**. २३, ८.

आऽरेभाणान् **८**. ३, ७.

आरेभाथे इत्याऽरेभाथे **४**. २८, ४.

आऽरेभे **१**. २८, ३; **४**. १७, ३.

आऽरेलिह **२०**. ९६, १४.

आरेऽशत्रुम् **७**. ९, १.

आऽरेहणम् **६**. ९, ३.

आऽरोचयन् **१३**. २, ३२.

आऽरोहणम् **५**. ३०, ७.

आऽरोहन् **३**. ६, ६; **१३**. १, ४३; २, ४२; **१७**. १, १०; **१९**. ३६, १.

आऽरोहन्तः **४**. १४, ६; **११**. १, ३७.

आऽरोहन्तम् **२०**. ३४, १३.

आर्चन् **१३**. ३, २३.

आर्जुनेयाय **२०**. ३७, २.

आर्तवाः **५**. २८, २; **१०**. ६, १८; ७, ५; **११**. ३, १७; ९, २०; **१५**. ६, १७; १७, ६.

आर्तवान् **३**. १०, ९; **११**. ८, १७.

आर्तवानाम् **१५**. ६, १८; **१६**. ८, २१.

आर्तवेभ्यः **३**. १०, १०; **१९**. ३७, ४.

आर्तवैः **५**. २८, १३.

आर्तिः **८**. ८, ९; **१०**. २, १०.

आर्तिम् **१२**. २, ३८.

आर्त्नीइवेत्यार्त्नीऽइव **१**. १, ३.

आर्त्या **३**. ३१, २.

आर्त्विज्येन **११**. ३, १४.

आर्द्रऽदानुः **१६**. ३, ४.

आर्द्रऽपविः **१६**. ३, ४.

आर्द्रऽपवित्रः **९**. ७, १०.

आर्द्रम् **१**. ३२, ३.

आर्द्रऽहस्ता **१२**. ३, १३.

आर्द्रा **१९**. ७, २.

आर्ध्नोत् **४**. ३९, १; ३; ५; ७.

आर्पयन् **५**. १९, २.

आर्पितः ६. ११२, ३; १०. ७, १४.
आर्पितम् १०. ८, ६; १०, ३३.
आर्पिता ११. ७, ९; १८. २, ६.
आर्पिताः १०. ७, १२; १३. ३, १०.
आर्पितानि ८. ९, १९²; १८. १, १७.
आर्यः ४. २०, ४; ५. ११, ३; १९. ४५, ४.
आर्यम् ४. २०, ८; ३२, १; २०. ११, ९; १७, ४; १२६, १९.
आर्याः १८. १, २१.
आर्याणि २०. ३६, १०.
आर्याय १९. ३२, ८.
आर्ये १९. ६२, १.
आर्शम् ४. ४, ५.
आर्षेयाः ११. १, १६; २५; ३२.
आर्षेयाणाम् १६. ८, १३.
आर्षेयान् ११. १, २६; ३५.
आर्षेयेभ्यः १२. ४, २; १२.
आर्षेयेषु ११. १, ३३.
आल ६. १६, ३.
आऽलभे ७. ११४, ७.
आऽलापाः ११. १०, २५.
आऽलिंगी ५. १३, ७.
आऽलुम्पेत् १२. ४, ३४.
आऽलेभिरे १०. १, ९.
आवः ४. १, १; ५. ६, १; २०. ३७, २; ३²; ६८, ८; १४२, १.
आवत् २०. १३७, ७.
आवत् २०. ११, ९; ३५, १५; ७७, ७.
आऽवतः ५. ३०, १³.
आवतम् २०. १२५, ४.
आवर्थुः २०. १२५, ५.
आऽवदानि ६. ६९, २; ९. १, १९.
आवन् २०. १४३, ६.

आवन् ४. २, ६.
आऽवपनी १२. १, ६१.
आऽवपन्तिका १४. २, ६३.
आवयः ६. १६, २.
आवयत् ४. ६, ३; ५. १९, २.
आऽवयम् ८. ६, २६.
आवरित्यावः २०. ९१, ४.
आऽवर्तनम् ६. ७७, २.
आऽवर्तयन्ति २०. ९२, १४.
आऽवर्त्स्यन् १५. ६, १९.
आऽवव्रीततः ५. १, ८.
आऽवसथान् ९. ६, ७.
आऽवहात् ६. १२३, १.
आऽवातु ४. १३, २.
आविः ४. २०, ५; ६. १२३, २; ७. ११३, १; ८. ३, २४; १०. ८, ६; १२. १, ६०; ४, २९; ३०; २०. ८, १; ११, ३; १६, ६; २८, २; ३२, १; ३९, ३; ७२, २; ७५, १; ७७, ८.
आविथ ५. २, ६; २०. ९, ३; ४९, ६; ५७, ३; ६३, ८; ७५, ३²; १०७, ९.
आविथ २०. २१, १०.
आऽविवासत् ७. २२, १.
आऽविवासताम् ८. ४, २१.
आऽविवासति २०. ६३, ६.
आऽविविशुः २. ३१, ५; १८. २, ४९; ३, ५९.
आऽविवेश १. १२, ३; ३. २१, १; २; ७. ४३, १; ९२, १; १२. १, २४; २, ३३; ५५; १६. १, ८; १८. ३, ५५; १९. ३, ३; ५९, २.
आऽविशते ४. ३६, ८.
आऽविशन् १८. ४, ५८.

आऽविशे ४. ३६, ७.
आऽविष्टः ३. २१, २; ६. ८५, १; १०. ३, ५.
आऽविष्टिता ५. १८, ३.
आऽविस्थितानि ५. २८, १.
आऽवृणानः १९. ४२, ३.
आऽवृतः १०. २, ३१; १३. ४, २; ३; ४; ५; ६; ७; ९; १७. १, २७.
आऽवृतः ६. ७७, ३; १०. ७, ४.
आऽवृतम् ६. १२५, २; ९. १४, १४; १०. ८, ४३; ११. ११, ४; १२. १, ८; २०. ९, २; ४९, ५.
आऽवृतम् १०. ५, ३७;
आऽवृता ९. ३, १७; १०. १, ३०; १२. १, ५२; ५, २; ७, १; १०, ७.
आऽवृताम् १०. २, २९.
आऽवृते २०. २४, ३.
आऽवृत्तः ९. १२, २३.
आऽवेशयन्तः ४. ३०, २.
आऽवेशयन्ती ७. ८४, ३.
आऽव्युषम् ४. ५, ७.
आऽशंसत १२. ४, ४४; ४६.
आशंत २०. ७१, २.
आशत २०. ९२, १५.
आऽशये २०. ९६, ११; १२.
आऽशरीकम् १९. ३४, १०.
आशवः ३. ९, ५; २०. ६९, ५.
आशवे १०. ६, ११; १२; १३; १४; १५; १६; १७; २०. ६८, ७.
आऽशसनम् ५. १९, ५; १२. ९, १; १४. १, २८.
आऽशसा ७. ५९, १.
आऽशसानाः १८. ३, २१.
आशाः ५. ७, ९; ६. ६२, २; ७. १०, २; ९. २, २१; १०. ५, २९; ८, ३६; ११. ८, ६; १९. १५, ६; ५२, ३.
आशानाम् १. ३१, १; २; ३.
आशाऽपालः १. ३१, ३.
आशाऽपालाः १. ३१, २.
आशाऽपालेभ्यः १. ३१, १.
आशाभ्यः १०. ५, २९; २०. २०, ७; ५७, १०.
आऽशाम् ६. ११९. ३; १९. ४, २.
आशाम्ऽआशाम् ४. १५, ८; १२. १, ४३; ५४.
आशारऽएषी ४. १५, ६.
आशाऽसंशितः १०. ५, २९.
आऽशासाना १४. १, ४२.
आऽशिरम् २०. २२, ६; ९१, ६; ९२, ३.
आऽशिषः ४. २५, ७; ५. २६, ९; ८. ९, २५; २६; ११. १०, २७; १२. १०, १०.
आऽशिषम् २०. ९१, ११.
आशिषम् ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८.
आऽशिषा १४. २, ९.
आऽशिषि ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
आऽशीः २. २९, ३; ५. ३, ५.
आशीरः ११. ३, २७.
आशीरः ११. ३, २६.
आशीत् ८. ३, १७; ११. ३, ३१.
आशीविषः १२. ८, ७.
आशुंगः ६. १४, ३.
आशुः २. १४, ६; १३. २, ३१; १९. १३, २.
आशुम् ७. ९०, १; १३. २, २; २०. ६८, ७; १०५, ३.

आशुऽमत् ६. १०५, १; २; ३.
आशू इति २०. ८६, १.
आशून्ऽइव ४. २७, १; २०. १६, २.
आऽशृण्वती ५. २०, ५.
आऽशृण्वन्तम् ६. १४२, २.
आश्नात् २. २७, ४.
आऽश्रावयन्तः ५. १३, ५.
आऽश्रेषम् ८. ६, २.
आश्विनम् ६. १३१. ३.
आर्षम् ८. ८, १८.
आष्ट्र ४. १, ५.
आष्ट्री इति ६. २७, ३.
आऽश्लेषाः १९. ७, २.
आस ७. ६८, १.
आस ४. ३२, २; ५. २, १; २०. १०७, ४.
आसः ९. १३, १०.
आसक्तिः १४. १, २६.
आसत ११. १०, ५; ६.
आसताम् ११. १२, २.
आसते ११. १०, ३२; १८. २, ४८; ५५.
आसते ५. १७, ११; १९, ३; ७. ७५, २; ९. १५, १८; १०. ४, ११; ८, ९; १०, २६; ३१; ३२; ११. ६, ११; १२; १०, १०; १३. २, २७; ६, ६; १८. २, १४; ४, ३६; २०. ५२, १; ५७, १४; ९२, १४; ९३, ४.
आऽसदे २०. २३, ९; १०३, २.
आऽसद्य ७. ६०, २; १८. १, ४२; ३, २०; ४, ४६; २०. ६७, ४.
आसन् ५. १८, १०; ६. ११२, २; ११. १०, १०; १२. १, ३७; १५. ३, १०.
आसन् ८. ३, २; १८. ३, ११; १९. ६०, १.
आसन् ३. १३, ५; ५. ४, ५[२]; ६. ३०, १; १३७, २; ७. ५, १; ९. ४, १४; १५, २५; १०. २, ४; ८, ३५; ४०; ११. ७, १४; १०, १; २; ५; १३. १, ४६; १४. १, ८; १९. ६, १५.
आसनि ६. ८४, १; १०. १०, २८.
आसन्ऽइषून् १८. १, ६.
आऽसन्दीम् १५. ३, २; ३; ९.
आऽसन्द्याम् १४. २, ६५.
आऽसंज्ञानाम् ९. ७, ४.
आसन्ऽवत् ६. १२, २.
आसऽभिः ६. ४९, २.
आऽससाद ६. २८, ३; १२. ३, १३.
आसा २०. ९१, १०.
आसाते १८. ३, ७०.
आसाते १. १४, ३.
आऽसादः १५. ३, ८.
आसाम् १. ३२, २; २. २, ३; १४, ६; ३. १३, ६; ४. २१, ३; ७. ७८, २[२]; ८. ७, १२[२]; १२. ४, ४५; २०. ११, ५; १६, ७.
आऽसिक्तम् ४. ७, १.
आऽसिक्ताः १२. ३, २५.
आऽसिञ्चन्ति ४. २७, २.
आसिथ १. २४, १.
आसिम ७. ६७, ३.
आसीत् ८. ९, १४; ११, ५; १३, २; ६; १०; १४; १४, २; ६; १०; १४; ११. १०, ७; १२. १, ८; १३. ३, १२; १८. २, ३३; ३, ३; १९. ५२, १; ५३, ८.
आसीत् २. २, ३; ४. २, ६; ७; ८; ५. १७, २; ६. ३०, १; ७. ८५, ४; ८. ८, ५; ८; १०, १; ९. ४, १३; १५; १४, ९; १०. ८, ३९; ४०; १४. १, ६; ७; ८; १०[२]; १४; १५. १, १; १८. २, २७; १९. ६, ६; ८; १०.

आसीइत् १२. १०, ४.
आऽसीदन्ति १४. २, ११.
आसीनः ९. १२, १९.
आसीनाः २. १४, ४; १२. १, २८; २, ३०.
आसीनाम् १८. ४, ४०.
आसीनाय ११. २, १५; ६, ७.
आसीनासः १८. ३, ४३.
आसु ३. १०, ४; ७. ११६, १; ८. ९, ११; २०. १२६, ११.
आसु १८. ३, १८.
आऽसुतेः ३. ७, ६.
आऽसुनोति २०. ८९, ५.
आसुरस्य ३. २२, ४.
आसुरी १. २४, १; २; ७. ३९, २.
आसुरीः ८. ५, ९.
आसुरे २०. १२९, ४.
आऽस्कुनोति १२. ४, ६.
आस्त १०. १०, १२; १७.
आऽस्तरणम् १५. ३, ७.
आस्ताम् ४. १६, ७; ८. ११, ६; १५. ३, ४; ५.
आस्ताम् १. १४, १; ९. ४, १२²; १३; ११. १०, २; ६; १४. १, ९; १०; ११.
आस्ते ४. ५, ५; ३४, ३.
आस्ते १०. ८, ३१; ११. ७, ९.
आस्तेयीः ११. १०, २८.
आस्थत् १३. १, ५.
आऽस्थाता ६. १२५, १.
आऽस्थानम् १. २३, ३; ३२, ३.
आऽस्थाने ६. ७७, १; ७. १०१, १.
आऽस्थितम् ४. १७, ८; ६. १४, १.
आस्नः १०. १०, २०.
आस्ना ६. ५६, ३; ७. ७७, ३.
आऽस्नाने १४. २, ६५.
आस्ने ६. १२, ३.
आऽस्पन्दमानाः ३. १२, ३.
आस्महे १३. ८, २; ५; ६; ९, १; २; ३.
आस्यत् ४. ६, ४; ६. ९०, १.
आस्यतः ६. ७६, २; ९. १३, ३.
आस्यन् ४. ६, ७.
आस्यम् ६. ५६, ३; १३९, २; ४; ७. ७०, २; ७३, ४; ५; १०. ७, ३३.
आस्याः १. १९, २.
आस्यानि ४. ३९, १०.
आस्याय ११. २, ६.
आस्ये ७. ५८, ८.
आस्येन ७. ५८, ८; २०. ३५, ३.
आस्रावऽभेषजम् ६. ४४, २.
आऽस्रावम् १. २, ४.
आऽस्रावस्य २. ३, ३; ४; ५.
आह ३. १६, २; ८. ४, १५; १६²; ९. ७, २; १२. ४, १७; १५. ११, ३; ४; ५; ६; ८; १०.
आह १. १६, २; ३. ४, ५; ८. ५, ५²; ११. ३, २८; २९; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १६. ९, २²; १८. २, ३७; १९. २४, ८²; ४४, ८.
आऽहतः १४. १, १२.
आऽहतम् १. ११, ४.
आऽहताः १०. ८, ४.
आहनः १८. १, ७; ९.
आऽहननम् १२. ९, १.
आऽहनने १२. १०, १.
आहनसम् ४. ३०, ६.
आऽहरन्ति ९. ६, ६; ९; १०; ११; १२.

आऽहराणि **३.** १५, २.
आऽहवनीयः **८.** ७, १३; **१५.** ६, १४.
आऽहवनीयस्य **१५.** ६, १५.
आऽहवनीये **८.** १०, ४.
आऽहवेषु **१८.** १, ४८.
आऽहार्यमि **९.** १, २३.
आऽहार्याणि **९.** ७, १.
आऽहितः **४.** ११, ८; **६.** १२९, ३; **७.** ५२, ८; **११.** ६, १३; ९, १; २; **१४.** १, २; **१९.** ५३, ३.
आऽहितम् **९.** १५, १[२]; **१०.** ३, १७; २३; २५; ७, १; २९; ३०; **१४.** १, ३५; **१७.** १, १९.
आऽहिता **१०.** ७, ३; १२; **११.** ९, २२; **१९.** ५४, २.
आहुः **३.** ११, ५; ७; २१, ४[२]; **४.** २, ५; **५.** १७, ४; **९.** २, ५; १४, २१; **१०.** ७, १९[२]; १०, २३; **११.** ८, ७; **१२.** ३, ४; ४, ५२; **१३.** २, ३६.
आहुः **१.** २५, १; **२.** २, ३; ३५, २; **४.** ११, ११; **५.** २८, ६; **८.** ९, ७; १६; १७; **९.** १, २; ४, ७; ८; ९; ५, ७[२]; १४, १२[२]; १५; १६; १९[२]; १५, ३; २८[२]; **१०.** ७, २५; ८, २३; ३३; १०, २६; **११.** ६, १२; १५; **१२.** २, ५३; ४, १०; ३३; ३६; **१८.** १, १४; **१९.** २७, ३; ३०, ३[२]; ५३, ३; **२०.** ८, २; ३४, ५; ८९, ३.
आऽहुत **६.** ५, १; **१२.** २, १८.
आऽहुतः **११.** १२, ५; **१८.** २, १०.
आऽहुतम् **७.** २१, २; ४८, १; ७०, १; ७७, ४; **१३.** १, ६०.
आऽहुता **६.** १३३, २.
आऽहुतिः **१०.** ९, ४३; **११.** १२, ५; १५; **१५.** १७, १०.
आऽहुतिम् **६.** ८३, ४; **७.** ७३, १; **१०.** ८, ३५; **११.** १२, १४; २६; **१५.** १४, ७; **१९.** ४, १.
आहुतिऽवृधम् **७.** ३३, १.
आऽहुतेः **३.** २२, ४.
आऽहुत्या **११.** १२, १२; **१५.** १४, ८.
आऽहुत्याः **१२.** १, १३.
आहुतऽयज्ञक्रतुः **९.** ७, १०.
आऽहृताः **२.** २६, ५.

इ

इक्षुणा **१.** ३४, ५.
इक्ष्वाकः **१९.** ३९, ९.
इङ्क्य **३.** १७, ६.
इच्छ **१८.** १, १६.
इच्छ **५.** २२, ६; ७; **६.** १३४, ३; **१४.** २, ३३.
इच्छः **१०.** १, ७.
इच्छत **८.** ४, १८.
इच्छत **४.** १५, १५.
इच्छतः **८.** ६, ४.
इच्छताम् **८.** ६, ४.
इच्छतु **६.** २०, १.
इच्छते **११.** ७, १७.
इच्छन् **६.** २७, १; ६०, १; **७.** १०८, १; **१९.** ५६, ३; **२०.** ४१, २; ८७, १; ९१, ४.
इच्छन्तः **१९.** ४१, १.
इच्छन्ति **२०.** १८, ३.
इच्छन्ती **७.** ७७, ८; **९.** १५, ५; **११.** ११, ८; **१४.** २, १९.
इच्छन्ते **१०.** ८, ५.

इच्छमानः **३.** १५, ३; ५; ६; **१९.** ७, १; **२०.** ९१, ६.

इच्छसि **१०.** १, २०.

इच्छसे **२०.** ११४, १.

इच्छस्व **१८.** १, ११.

इच्छात् **४.** २१, ५; **६.** १३३, १; **१२.** ३, ३४; ४१; ४२;

इच्छामि **४.** २१, ५.

इच्छेत **१२.** ४, १३.

इटःऽइव **६.** १४, ३.

इटस्य **९.** ३, १८.

इडः **६.** ६३, ४; **१८.** १, ४३; ४, ४७.

इडया **३.** १०, ११; **६.** ६२, ३.

इडा **५.** १२, ८; २७, ९; **७.** २८, १; **११.** ९, १८; **१५.** ६, २०.

इडाम् **१८.** ४, ३०.

इडायाः **३.** १०, ६; **१५.** ६, २१.

इत् **१.** २, ४; १७, २; ३; ३४, २; ४; **२.** २, ४; २७, १; ३०, २; **३.** ७, ५; ८, ४; १३, ५^{२}; ६; १५, ८; १६, ५; १७, २; ३; १८, ४; २०, ६; **४.** २, ५; १७, ८; २१, २^{२}; ३; २४, १; २७, ६; २८, ४; ३७, १२; **५.** १, ६; २, १; १३, १०; ११; १४, ९; १७, ३; ८; **६.** २२, १; २६, ३; ५०, १; ५१, २; ३; ५५, २; ५७, १; ६३, २; ४; ८४, ३; ९१, ३; १०१, १; ११९, १; १२०, १; १२१, २; १२२, २; १३४, ३; **७.** १९, २^{२}; २१, २; २२, १; ३७, १; ३९, ४^{२}; ५२, ६; ५९, २; ९३, १; **८.** ४, १२; २१; ५, १२; १६; **९.** २, १९; २०; २१; २२; २३; २४; ४, २१; ५, ६; ६, २; १४, ८; १६; १५, १; १०; १५; १८; २१; २२; **१०.** ४, १; ६, ७; ८; ९; १०; १४; १५; १६; १७; १०, २४; **११.** १, ६; ३४; १०, ७; **१२.** २, ३६; ३, ९; ४७; ४, १८; २१; ४८; **१३.** १, १२; **१४.** १, ५; ७; १६; २९; ३०; ३२; ५७; २, ४१; **१७.** १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; **१८.** २, ६; ३७; ५०; ५१; ५८; ३, २१; **१९.** २६, १; ३२, ७; ३४, ९; ४५, ३; ५०, ६; ५५, ६; ५९, ३; **२०.** ६, ६; ७, १; १०, २; १२, २; ६; १४, २; १६, २; १७, २; ३^{२}; १८, २; २१, ३; ७; २४, ८; २५, १; ६; २७, १; २९, २; ३५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; ३६, १; ३७, ८; ३८, ४; ५; ४७, ४; ५; ५५, २; ५६, १; ५७, २; ५८, १; ५९, २; ३; ६२, २; ६३, ३; ४; ६४, ४; ६५, १; ६७, १; ७; ६८, २; ५; ६; ७०, ७; ८; ७१, ११; १६; ७३, १; ४; ५; ६; ७५, ३; ७६, १; ८२, १; २; ८५, १; ८७, १; २; ५; ८९, ९; ९२, ८; १०; ११; ९३, ५; ९६, ३; ९८, १; ९९, २; १०७, ४; ११०, ३; १११, २; ११२, २; ११४, १; २; ११५, १; २; ३; ११६, २; ११८, ३; १२३, १; १२४, ६; १२६, ३; १४; १६; १७; १३७, ११; १३९, ३; १४०, ४; ५; १४३, ४; ९.

इत **३.** १, २; २, ४; ८, ६^{२}; १३, ७; १९, ७; ३०, ५; **४.** ३७, ३; ४; ५; **६.** ९४, २^{२}; **७.** ७९, २; १०२, ७; **८.** ७, १६; **११.** ८, १८; **१२.** २, ३०; ३४; **१८.** १, ५५^{२}; ४, ३७; **२०.** ६८, ११.

इतः **१.** २०, ३; २३, २; ३; **२.** १४, ४;

५; ६; **३.** ११, ६; ३१, ४; **४.** ३, १; ६, २; १४, ९; १७, २; २५, ४; ३७, ११; **५.** ४, १; ३; २२, १; ३१, १०; **६.** १४, ३; २३, २; २५, १; २; ३; ८३, ३; ९५, १; १२६, २; **७.** २७, ५; ६७, १; ८८, २; १००, ३; ११९, २; १२०, १^{२}; २; ३; **८.** १, १८; २, ८; ६, ७; ११; १४; २३; २५; ८, २४^{२}; ९, ६; **१०.** १, १४; १७; २०; २४; ३०; **११.** २, १२; १४; २७; ७, ११; १०, ७; १२, ९; १४; **१२.** १, ४९; २, २; ३; **१३.** १, ३९^{२}; २, १३; **१४.** १, १७; १८; २०; २, १९; ३३; ३६; **१८.** १, ६१; २, २७; ५१; ५४; ३, ३८; **१९.** ३४, ३; ३९, ६; ४४, ७; **२०.** २४, ३; ७०, ६; ९६, ११; १३; १४; १५; १६; १०५, ३.

इतन **३.** १४, ४; **५.** ८, ३; **६.** ८३, २; **१०.** ५, २३.

इतम् **१.** २७, ४; **६.** ११८, ३; **१२.** ३, ४४; **१८.** ४, ४९.

इतरः **१२.** २, ८; २१.

इतरऽजनाः **११.** १२, १.

इतरऽजनाः **८.** १४, ९; १२; **९.** १२, १७; **११.** ११, १६.

इतरऽजनान् **८.** १४, ९.

इतरम् **११.** १०, ३१; **१२.** २, ७.

इतराः **११.** १, १३.

इतरान् **३.** ११, ५; ७.

इतराभिः **१८.** २, ९.

इतरासु **३.** १०, ४; **८.** ९, ११.

इताम् **७.** ५५, ३; **१४.** २, ११.

इति **१.** ३, १; २; ३; ४; ५; ६; ७; ८; ९; ७, ४; **३.** १३, ४; १६, २; ३१, ५; **४.** १७, २; २०, ६; **५.** १७, ३; ४; १८, ७; १९, ९; २३, १; **६.** ८१, ३; ८२, २; ८४, १^{२}; १२८, १; १३०, २^{२}; **७.** ७८, १; ८८, २^{२}; ११४, ६; **८.** ४, १५; १६^{२}; ९, १८; १०, १; ११, २; ४; १३, १; ५; ९; १३; १४, १; ५; ९; १३; १५, २; **९.** १, २४; ४, १२; ७, १; २; १४, १६; **१०.** १, ७; १५; २, ५; १७; १०, २३; **११.** १, ७; २, २८; ३, २४^{३}; २६; २७; २८; २९; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ८, ७; १०, २२^{२}; ३२; **१२.** ४, १; ६; ४२^{२}; ४८; ४९; ५२; १०, ४; **१३.** ८, २; ५; ६; ९, १; २; ३; **१५.** १, ४; ८; ३, १; २; १०, ३; ४; ११, २; ३; ५; ६; ८; १०; १२, २; १३, १३; १७, १०; **१८.** १, ४९; २, २२; ४८^{२}; ४, ७; **१९.** ३४, ६; ४४, ९^{२}; **२०.** ३४, ५^{२}; ११२, २; १३७, ५.

इतिहऽआसः **१५.** ६, ११.

इतिहऽआसस्य **१५.** ६, १२.

इत्थम् **३.** १३, ७; **६.** १३५, १; **८.** ९, २२.

इत्था **१.** २०, ४; **४.** १, ६; **२०.** २४, ३; ४१, ३; ७७, ३; ९२, १४; ९४, ७; १०९, १.

इदत्ऽवसुः **१३.** ९, ३.

इदम् **१.** ७, ३; ५; ८, १^{२}; १६, ३^{२}; २३, १; २४, २^{२}; ३; ४; २९, ५; ३०, २; ३१, १; ३२, १; **२.** १, १; ३, ३; ५; १२, २^{२}; ३^{२}; १३, ३; २६, ५; ३०, १; ३६, ७; **३.** ४, ५; ८, २; १३, ७^{२}; १५, ४; १९, १; २३, १; २४, ४; २९, ७; ८; ३१, ५; **४.** ४, २; ५, ५; ६, ८; ७,

१; २; ८, १; ९, ७; १२, १; १६, १; ४; २३, ७; २६, ७; २७, ६; २८, १; ३०, ३; ३६, ८; ३८, ३; **५.** ८, २; १२, ८; २६, १२; २७, ९; १२; २८, ६; २९, १; **६.** १३, २; ३; २७, १; २९, २; ३[२]; ३३, १; ४४, १; ४७, ३; ५१, ३; ५३, १; ५४, १; ५७, १[२]; ६८, ३; ७७, १; ८३, ४; ८८, १; ८९, १; ९०, १; ९४, ३; ९७, १; १००, २; १०४, २; १०६, २; ११६, ३; ११७, १; २; १२२, ५; १२८, १; १३१, २[२]; १३६, ३; **७.** १, २; १२, १; १८, ४; १९, १; २१, ६; २६, २; २७, ४; ३६, १; ३९, १; ६०, २; ६६, १; २; ७०, २[२]; ७८, २; ७९, २; ८२, १; ९४, ३; ११४, १; ५[२]; **८.** २, २५; ३, ८; ८, १६; ९, २२; १०, १[२]; **९.** १, १७; २, ८; ३, ५; ५, २०; ३८; ७, १; १५, १५; **१०.** १, ९; २, २२; २३; २४; २५; ४, ७[२]; १०; ५, १५; १६; १७; १८; १९; २०; २१; ३६[२]; ६, १३; ७, ३५; ८, २; ५; ६; ९, २७; १०, ११; २६; ३४; **११.** १, ११; २७[२]; २८[२]; २, १०[२]; ३०; ३, २४; ६, १; ८; १८; ७, १४; ८, ५; ९; ११; १९; २०; १०, १६; ३२; **१२.** १, ३; ५३; २, १; ३, ४४; ४५; १०, ४; **१३.** १, १[२]; २०; २३; ५४; ५५[२]; २, ४४; ४५; ३, १५; ४, १२; ५, ७; **१४.** १, ३८; ४५; ४६; ५६; २, ९; १९; ४६; ७४; **१६.** १, ४; ७, ८; ८, ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२]; १९[२]; २०[२]; २१[२]; २२[२]; २३[२]; २४[२]; २५[२]; २६[२]; २७[२]; २८[२]; २९[२]; ३३[२]; **१८.** १, ४६; ५२; ५३; २, २; ५०; ५१; ३, २; ७; ६४; ४, ३५; ३७; ४४; ५१; ५२; ५६; **१९.** ६, ४; ९, १; ४; ११, ४; ६; १४, १; २४, ६; २७, ११; १२; १३; ३७, १; ४४, ७; ८; ४८, ३[२]; ५२, ५; ५६, २; ४; **२०.** ३, १; १६, १२; २१, २; ३; ७; ३२, ३; ३४, १५; ३८, १; ४७, ७; ६७, ७; ८५, ३; ८७, ६; ९६, २; ११३, १; १२६, १२.

इदम्ऽइदम् **९.** ५, २३; २४; **२०.** १४, ३; ६२, ३.

इदा **२०.** ९७, १.

इदानीम् **३.** १६, ४; **८.** ३, ५.

इदाऽम् **९.** ७, १.

इदावत्सराय **६.** ५५, ३.

इद्धऽअग्नयः **२०.** २५, ४.

इद्धः **३.** ८, ३; **१९.** ६४, ४.

इधीमहि **१८.** १, ५६[२]; ५७[२]; ४, ८८; **२०.** १०२, ३.

इध्मः **१९.** ६, १०.

इध्मम् **१०.** ६, ३५; **१२.** २, ५४.

इध्मेन **३.** १५, ३; **५.** ८, १; **१९.** ६४; २.

इध्यते **१३.** १, ४८; ५०; **२०.** १०२, १; २.

इध्यसे **६.** ६३, ४.

इध्यस्व **२.** ६, २.

इध्यस्व **११.** १, ४.

इनः **२०.** २१, २; ९४, ४.

इनऽतमम् **५.** २, ७; **२०.** १०७, १०.

इन्दवः **६.** २, २; **२०.** ६, ४; ५; १३, १; ११८, ४; ११९, २.

इन्दवः **७.** ११४, ६.

इन्दवे **१८.** ३, ३९.

इन्दुः **१८.** ३, ५४; ४, ६०; **२०.** ९५, १; १३७, ५.

इन्दुंऽभिः **२०.** २१, ४[२]; १११, १; २; ३.

इन्द्रं **२.** ५, १; २; **३.** १, ५; २, ३; **४.** २२, २; **५.** ३, ८; ८, २; ५; ९; **६.** ५, २; ४०, ३; **७.** ३२, १; ८२, २; ११५, ३; **८.** ४, २४; ५, १७; ६, १३; **१३.** १, ३०; **१४.** १, ६२; **१८.** ३, ६७; **१९.** १३, १; ७०, १; **२०.** १, १; ३, १; ५, ३; ६, १; २; ३; ४; ६; ९; ७, ४; ११, २; १८, १; १९, १; २; ३; ६; ७; २०, १; २; ४; २३, ८; २४, ५; २५, ७; २७, ४; २९, १; ४; ३३, २; ३५, १६; ३८, १; ४२, २; ४७, ७; ५२, २; ५७, ४; ५; ७; १५; ६१, ६; ६२, १०; ६४, २; ३; ५; ६९, ४; ७०, १०; १९; २०; ७१, ७; १२; १४; ७९, १; ८०, १; ८३, १; ८४, १; २; ३; ९३, ३; ९६, १; २; ९७, २; ९९, १; ११६, १; ११८, १; १२०, २[२]; १२५, ५.

इन्द्र **१.** २, ३; १९, १; २१, २; ३; ४; **२.** ५, ४[२]; १२, ३; २७, ७; २९, ३; **३.** १, ३; ४; ३, ६; **४.** ४, ४; २२, १; ३; **५.** ८, ७; ९[२]; २३, २; २८, ४; **६.** ४५, ३; ६६, १; ३; ८२, ३; ९८, २; ३; ९९, १; १२६, ३; **७.** १३, ३; ५२, ४; ७५, २; ७६, १; ८१, २; ८९, ३; १०२, २; १२२, १; **८.** ४, ८; १९; २२; ५, १५; ८, ७; ९, २१; **९.** ४, २३; **११.** ११, २३; **१३.** १, ५९; ८, १; २; **१४.** १, १८; ४१; २, ६४; **१७.** १, ९; १०; ११[३]; १२; १३[४]; १४; **१९.** ८, ६; १३, ५; १५, १; २; ४; ४२, ३; ५५, ६; **२०.** ३, २; ३; ५, १; ५; ६, ५; ८, १; ९, ४; १२, २; ४; ५; १४, २; १५, ४; ५; ६; १८, ४; २०, ३; २१, २; ३; ५; ७; १०; ११; २३, १; ४; ७; ९; २४, १; २; ७; ८; ९; २५, १; २७, १; ३; ६; २८, ४; २९, ३; ५; ३०, ५; ३२, २; ३; ३३, १; ३; ३४, १८; ३६, ४; ९; १०; ३७, २; ६; १०; ११; ३८, २; ३; ५; ४२, ३; ४३, २; ४६, ३; ४७, ८; ९; ४९, ७; ५०, २; ५५, २; ३; ५६, ३; ६; ५७, ६; ६०, २; ५; ६२, २; ६; ७; ६३, ७; ६४, १; ६८, ९; ६९, ५; ८; ७०, १; १७; ७१, ५; १०; ११; १३; ७२, २[२]; ३; ७३, २; ७४, १; २; ३; ४; ५[२]; ६; ७; ७५, १[२]; २[२]; ७६, ३; ४; ५; ६; ८१, १; ८२, १; ८३, २; ८५, ३; ८६, १; ८७, २; ३; ४; ६; ८९, ३; ४; ७; ९२, २०; ९३, ५; ६; ७; ८; ९५, ३; ४; ९६, ५; ९८, १; २; १००, १; १०५, १; २; १०६, २; १०८, १; १११, १; ११२, १; ३; ११४, १; ११५, ३; ११७, १; २; १२०, १; १२१, १; २; १२५, १; १२६, २; ४; १५; १८; २२; १३७, १०; ११.

इन्द्रंऽइन्द्र **३.** ४, ६.

इन्द्रंऽइषिताः **७.** ७३, २.

इन्द्रंऽऋषभा **१२.** १, ६.

इन्द्रंः **१.** ७, ३; ४; ७; ९, १; १६, २; २१, १; २६, २; २९, १; **२.** ५, ३; १४, ४[२]; २७, ३; ४; ५; २९, ७; **३.** १, ६; ३, ३; ८, २; ११, ३; ४; १२, ४; १३, २; ३; १४, २; १५, ६; १७, ४; २२, २; २७, २; **४.** ३, ५; ११, २; ३; ७; १९, ८; २१, २; ५[२]; २३, ५; ३२, २; **५.** ८, ८; १८, ५; ६; १४; २१, ८; ११; २३, १; २४, ११; २५, ४; ६; २६, ३; ११;

२९, १०; ३१, १२; **६.** ३०, १; ३३, ३; ३९, ३; ४०, २; ४७, २; ५८, १; २; ३; ६५, ३; ६६, २; ६७, १; २; ७५, १; २; ८७, ३; ८८, २; ९४, ३; ९७, १; ९८, १; १०३, २; ३; १०४, ३; १११, ४; १२२, ५; १३८, २; १४१, १; **७.** २५, १; ४५, १; ५३, १; ८६, ६; ९१, १; ९४, २; ९६, १; ९७, १; ९९, १; ११५, १; **८.** १, १५; ४, १६; २१; २५; ५, ३; ५; १०; १४; १८; २१; २२; ८, १; १८; २३; ११, ५; १४, २; **९.** १, १५; २, १३; १७; १८; ४, २१; १२, १; २०; १४, १९; **१०.** ३, ११; ४, १०; १२; १६; १७; १८; ५, ४७; ६, ७; ८, ४२; १०, ९; **११.** १, २७; ७, ७; १६; १९; ८, २३; ९, १; १०, ८; ९; ११, २०; २५; १२, ११; १६; २७; **१२.** १, १०; १८; ४०; २, ५४; ३, २४; **१३.** १, २७; ५१; ३, १३; ८, १; **१४.** १, ३७; २, ४२; **१५.** १०, ६; १४, ३; **१७.** १, १८; **१८.** ३, १२; २५; ४, १५; **१९.** ५, १; ६, ७; ९, ६; १२; १०, ६; १३, २; ४; ७; ९; ११; १५, ३; १७, ८; १९, ९; २०, ३; २४, ८; २६, ४; २७, १; ९; ३४, ८; ९; ४३, ६^{२}; ४५, ७; ४६, ३; **२०.** २, ३; ५, २; ७, ३; ११, १; ३; ४; ५; ७; ९; १०; १२, ३; ७; १३, १; १७, ३; ११; १२; २०, ५; ६; ७; २५, ६; २८, १; ३४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १३; १४; १५; ३५, ९; १०; १५; ३६, ७; ३८, ५^{२}; ६; ३९, २; ४१, १; ४६, २; ४७, २; ५^{२}; ६; ५३, ३; ५६, १; ५७, ८; ९; १०; १३; ५९, ३; ६३, १^{२}; २; ४; ५; ६; ६७, १; ६९, ७; ७०, ८^{२}; ९; १५; ७१, १; ७३, ४; ५; ७६, १; ८; ७७, ५; ८७, १; ७; ८९, ११; ९१, ६; १२; ९२, ४; ८; ११; ९४, १; ११; ९६, ३; ८; ९; ९९, २; १०४, ३; १०७, २; ११३, १; ११५, २; ११८, ४^{२}; १२४, ४^{२}; ५; १२५, ६; ७; १२६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३^{२}; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; १३७, ७; ९; १३; १३८, १.

इन्द्रःऽइव **४.** ५, ७; ३१, ५; **६.** ८७, २; **९.** ४, ११; **१९.** २८, ३; ४६, २.

इन्द्रऽगुप्ताम् **१२.** १, ११.

इन्द्रऽजाः **४.** ३, ७.

इन्द्रऽजालेन **८.** ८, ८.

इन्द्रऽजूतम् **६.** ३९, १; २.

इन्द्रऽज्येष्ठाः **३.** १९, ६; **७.** ८४, २.

इन्द्रऽधनुः **१५.** १, ६.

इन्द्रऽपत्नी **२०.** १२६, ९; १०.

इन्द्रऽपुत्रे **३.** १०, १३.

इन्द्रम् **३.** ३, २; १०, १२; १५, १; १६, १; २०, ७; २१, ८; **४.** २१, ५; २२, ५; २४, ७; **५.** २, ९; ३, ११; **६.** ३८, १; २; ३; ४; ३९, २; ५४, १; ९७, ३; **७.** ३९, २; ४८, ३; ९१, १^{४}; १०३, १; ११५, २; **८.** ४, २०; **९.** ४, ९; १५, २८; **१०.** ७, ३०; १०, १०; **११.** ८, १; **१२.** १, ३७; २, ४७; **१५.** १०, ४; ५; ११; **१७.** १, १; २; ३; ४; ५; **१८.** १, ४८; ३, २२; **१९.** १३, ६; १५, २; १८, ८; २४, २; ७; **२०.** ६, ७; ८, ३; ९, १; १०, २; ११, ८; ११; १२, १;

६; १४, ३; १७, १; ४; ७; १९, ५; २२, ४; २३, ५; २४, ३; ४; २६, १; २७, ५; २९, २; ३१, १; ३६, १; ३; ५; ३८, $४^{३}$; ३९, १; ४४, १; ४७, १; $४^{३}$; ४९, ४; ५१, १; ५४, १; २; ५५, १; ५९, २; ६१, ४; ६२, ३; ८; ६५, १; ६६, १; ६८, ४; ११; १२; ७०, ६; $७^{३}$; $११^{२}$; १६; ७१, १५; ७२, $१^{२}$; ८५, १; ८९, १; २; ८; ९२, १; १७; १८; ९३, ४; ९५, १; १०५, ५; १०७, १२; ११०, २; ११८, $३^{४}$; १२५, ३; ४; १२६, १; १२७, २; १२; १२८, ३.

इन्द्रंऽमेदिनौ **११.** ११, १८.

इन्द्रंमेदिऽभ्याम् **११.** ११, ४.

इन्द्रंऽमेदी **५.** २०, ८.

इन्द्रऽयोगैः **१०.** ५, ३.

इन्द्रंऽवन्तः **५.** ३, ३.

इन्द्रवायू इतिं **३.** २०, ६.

इन्द्रऽवाहः **२०.** ९४, ३.

इन्द्रऽवाहा **२०.** १००, ३.

इन्द्रऽसंधया **११.** १२, ९.

इन्द्रंऽसखा **४.** ५, २; २२, ६; ७.

इन्द्रंस्य **२.** ३, ६; ५, ५; ३१, १; **३.** १९, ४; **४.** २२, ४; २४, १; ३७, ८; ९; **५.** ६, ४; ११; १२; १३; १४; ८, ४; **६.** ३३, १; २; ५१, १; ८२, १; ८५, २; ८६, १; ९२, १; ९९, २; ३; १२५, २; ३; १२६, २; **७.** २७, ६; ५४, २; ७५, १; ११६, १; **८.** ४, १३; ९, २३; **९.** २, ६; ४, ७; ८; **१०.** ४, १; ५, $१^{५}$; $२^{५}$; $३^{५}$; $४^{५}$; $५^{५}$; $६^{५}$; ८; **१२.** ४, ५१; **१६.** १, ९; **१८.** ४, ५८; ६०; **१९.** १३, १०; ३०, ३; ३५, १; ४६, ४; **२०.** ११, ६; १५, २; १९, ४; ४०, २; ५१, ४; ५८, १; २; ६८, ६; ७०, ४; १३; ८७, ५; ९७, ३; १०९, २; १३७, १; ६.

इन्द्राग्निऽभ्याम् **५.** ३, १०.

इन्द्राग्नी इतिं **१३.** १, ३१.

इन्द्राग्नी इतिं **१.** ३५, ४; **३.** ३, ५; **४.** ३०, १; **५.** ७, ६; **६.** १०४, ३; १३२, ४; **८.** १, २; १६; २, २१; **९.** २, ९; ३, १९; **१०.** १, २१; **११.** १०, ५; **१४.** १, ५४; **१९.** १०, १; १६, २; २०, १; २७, १५.

इन्द्राग्नी इतिं **३.** ११, १; **९.** १, १२; **२०.** ९६, ६.

इन्द्राग्न्योः **९.** १, १२; **१६.** ८, २७.

इन्द्राणि **२०.** १२६, १२.

इन्द्राणी **१.** २७, ४; **६.** १३२, ३; **७.** ५१, २; **९.** १२, ८; **१५.** ६, २०.

इन्द्राणीऽईव **१४.** २, ३१.

इन्द्राणीम् **२०.** १२६, ११.

इन्द्राण्याः **१५.** ६, २१.

इन्द्रात् **११.** १०, ९; **२०.** ४२, १.

इन्द्रापूषणा **१९.** १०, १.

इन्द्रापूषणा **६.** ३, १.

इन्द्राय **१.** ९, ३; **४.** २१, १; **५.** २, ८; २७, १२; **६.** २, १; ३; **८.** ९, २४; **९.** ४, ३; ५, २; **१२.** १, ३८; ३, ५६; **१८.** १, ३७; ३, ५४; **१९.** ४३, ६; **२०.** २१, १; २२, ६; ३०, २; ३१, १; ३५, १; २; ४; ५; ८; ६०, ६; ६२, ५; ६८, १०; ६९, २; ७१, ६; ८; १६; ७६, ७; ९१, १; ९२, ३; ६; ७; ९५, २; १०७, ११; ११०, १; ११९, १; १३७, ४; ५.

इन्द्रावरुणा **१९.** १०, १.

इन्द्रावरुणा **७.** ६०, १; २.

इन्द्रासोमा १९. १०, १.
इन्द्रासोमा ८. ४, १; २; ३; ४; ५; ६; ७.
इन्द्रियम् ३. २२, ५; ५. ९, ८; ६. १३३, ४; ७. ६९, १; १२. ६, १; १५. १०, १०; १९. ४२, ४; २०. १५, ३; ५०, १; १०६, १.
इन्द्रियऽवान् १५. १०, १०.
इन्द्रियाणि १. ३५, ३; १९. ९, ५; २०. २०, २; ५७, ५.
इन्द्रियाय १९. ३७, २.
इन्द्रियेण ६. १२४, १; १६. १, ९; १९. ३३, २; ४२, ४; ४५, ७.
इन्द्रियैः १९. २७, १.
इन्द्रे १०. ७, २९; ३०^{3}; २०. ३०, ३; ५९, ४; ६८, ५; ८९, ६; ११८, ४^{2}; १२२, १.
इन्द्रेऽइव १. ३५, ३.
इन्द्रेण २. २९, ४; ३. ५, ४; ६, २; २१, ३; ५. १४, ७; २०, १२; २१, ११; ६. ६५, ३; १०४, २; १२६, १; १२९, १; ७. ४२, १; ९५, २; ९८, १; १०३, १; ९. ३, ३; १०. ४, १२; ९, १; ११. १२, ९; १२. ४, ५०; १३. १, ३; १८. ३, ४८; १९. १३, ३; ३१, ७; २०. २१, ४; २८, ३; ३९, ४; ४०, १; ७०, ३; १०९, १; १४१, २.
इन्धते ४. २३, १; ८. १, ११.
इन्धते ११. ३, १७; १२. १, २०; २, ११; १३. १, ४०; १८. ४, ४१.
इन्धानाः ५. ३, १; १९. ५५, ३; ४.
इन्धाम् १२. २, ७; ३, २५.
इन्धे ५. १८, ५; ७. ८७, ६; ११. ३, १८.
इन्वत ५. २, ६; २०. १०७, ९.

इन्वथ ४. २७, ३.
इमः ११. २, १८.
इमम् १. ८, २; ९, १; २; ३; ४; १०, १; १५, १; २; ३०, १^{3}; २. ६, २; ९, १; १३, १; २; २६, २; २८, १; ३^{2}; ५; ३५, ५; ३. ३, ४; ६; २१, ८; ४. १३, ४; २२, १^{2}; २; २७, १; ३४, ८; ३८, ५; ५. ३, ११; ४, ६; ५, ४; २७, ८; २८, ४^{3}; ३०, १४; ६. ५, २; ३०, १; ३५, २; ५४, २; ६३, ३; ८४, ४; ९१, १; ९५, ३; ९७, ३; १११, १; १३८, १; ७. २, १; ५, ५; ९, १; २१, ५^{2}; २९, १; ५५, ४; ६०, १; ७७, ९; ७९, २; ८३, २; ८७, १; १०२, ८; १२१, २; ८. १, ६; १८; २, ५; ७; ८; १०; २०; ५, १२; १३; २०; २१; ७, २; ५; ७; १९; २२; ९. २, ७; ५, १७; ११, १३; १४, ३; १०. २, २०^{2}; २१^{2}; ३, १२; ६, १७; २९; ११. १, ४; १६; १८; ११, २६; १२. २, ४; ७; २३; ४३; ४७; ३, ४; ३२; ३७; १४. १, ३२; ३३; २, ८; १३; १८; २३; २५; ४०; ७०; ७३; १७. १, ११; १८. १, ६०; २, ५; २७; ३, ५२; ५३; ६०; ४, २८; ४०; ५४; १९. १, १; २^{3}; ३; १३, ६; २४, १; २; ३; ४; २८, १; ३०, १; ४२, ३; ४६, २; ५४, ५; ५८, ५; ६; २०. ३, १; ११, ५; १३, ३; २४, ७; ३८, १; ४७, ७; ६९, ७; ९४, ९; ९७, २; १२६, ४; १४३, ४.
इमा ३. २०, ८; ५. २, ८; २२, ८; ७. ९२, १; ८. ४, ६; ९. १४, २; ७; ११. २, ११; १३. ३, १८; १७. १, १६; १८. १, ५१; १९. १३, १; ५३, २; ३; २०. २३,

३; ३४, ४; ६३, १; ७३, १; १०७, ११; ११७, ३; १२४, ४; १४१, ४.

इमाः १. १७, ३; २. १०, ४; ३. ३, ३; ४, २; १२, ९; २४, ३; ४. २, ५; २०, २; २१, ५; ५. १३, ९; २८, १०; ६. २१, १; ८५, ३; ९८, २; १२२, ५; ७. १०, २; २०, १; ३६, २; ८. ७, १३; ९. ३, २३; ४, ६; १०. १, ११; ६, ९; ८, ३७; ३८; १०, ४; ११. १, १४; १७; २७; ६, १९; १२. १, ४२; २, ३१; ३, ३०; १४. २, ५२; १५. १५, ७; ९; १६, ७; १८. ३, ५७; ४, ३९; १९. ८, ६; ३२, ४; ४५, ४; ५३, ५; ७; २०. ६, ८; ११, ५; १७, ८; ७५, २[२]; १०४, १.

इमान् ६. १७, २; २८, २; ५०, २; ७४, ३; ८४, २; ११. १, ११; १२. २, ३२; ५५; १४. १, ५६; २, २६; १८. २, २१; ३, ६२; ४, ५०.

इमानि ७. ७०, २; १०. ४, ७; १३. १, १४; १९. ९, ५.

इमाम् १. १८, २; २. ३६, १; ३. १२, ४; ७[२]; ८; १५, ३; ४; १६, ३; १७, ७; १८, १; ६. १२५, ३; १३३, १; ८. २, १; ६, ९; १६; ११, २; ९. ३, १५; १०. २, १८; ६, १२; ८, ३६; ११. १, ५; ९; ७, ९; १२, १४; २६; १४. १, ३५; ३६; ५३; ५४; ५५; ५९; २, ४; २८; ५३; ५४; ५५; ५६; ५७; ५८; १५. १३, १३[३]; १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४, ५; २०. ११, ८; ९१, १; ११७, ३.

इमे २. ६, ३; ३. १, २; ४. २४, १; ३८, ६; ५. ८, २; ६. ८, ३; २८, २[२]; ८८, १; १२६, ३; ७. ६२, २; ८४, २; ८. ८, १६; २४; ९, ७; ९. १४, १२; १०. ४, ११; ६, ३१; ७, ४४; ८, ३१; ९, १२; ११. १, १८; २, ९; १२. १, १५; २, २१; २२; १३. ४, १०; ६, ६; १४. २, ५९; १५. १५, ८; १८. ३, ६१; २०. ६, ४; १५, ४; १७, ३; २४, ५; ६९, ३; ८४, १; ८५, ३; ९६, १; १४०, ३; १४१, ४[२];

इमे इति ३. ३१, ४; ५. १२, ९; २०, ७; ६. ५८, १; ८. ५, ३; १०. ७, ३५; ८, २; ११. ७, ८; ११; १३. ३, १; १९. १५, ५; ३१, ११; २०. ८०, १.

इमौ ४. १३, २; ६. ७८, २; १०. २, ६; १४. २, ६३; १८. २, ५६.

इयंक्षति १८. १, २३.

इयंक्षमाणाः ४. १४, ९.

इयर्थ ८. १, १०.

इयम् १. ३४, १; २. ८, २; २५, २; ३०, ५; ३६, ३; ४; ३. १०, ४; ४. १, २; ४, ३; १६, ३; ३७, ६; ३८, ६; ५. २५, २; २६, ६; ३०, १६; ६. १७, १; २; ३; ४; ६०, २; १०९, १; ७. ३९, ५; ५८, १; २; ७७, ८; ८. ४, ६; ९, ११; १०, १; ११, २; ९. २, १५; ४, ८; ५, २०; ६, १७; १५, ५; १२; १४; १०. २, २४; ५, ४३; ८, २६; ११. १, १; ६; ८; ११; ३, ११; ७, ४; ११, ४; १२, ४; ६; १२. २, २७; ३, ९; ११; १४. १, १८; ५२; २, १३; १४; २०; २८; ६०; ६३; ७४; १५. १०, ६; १७, १; १८. ३, १; ४, ५०; १९. ९, ३; २०. १५, ५; १४३, ७.

इयर्त ६. २२, ३.
इयर्ति २०. ७०, १४.
इयर्मि २०. ११, २.
इयर्मि २०. २९, ७; ३३, २.
इयानः २०. १२२, २; १३७, ७.
इयानासः २०. ९१, ८.
इया३म् १२. ४, ४२.
इयाय १०. ७, ३१.
इरज्यति २०. ७०, १९.
इरज्यन्त २०. १२, २.
इरस्यसि २०. १२६, ३.
इरा ९. १२, १२.
इरा १५. २, १९.
इराऽइव ३. २९, ६; ५. १३, १.
इराऽक्षीरा १०. १०, ६.
इराम् ४. ११, १०; १९. ३१, ३.
इराऽवति ८. ११, ४; १३, ९.
इराऽवन्तः ७. ६२, ६.
इरिणा ४. १५, १२.
इर्यः ३. ८, ४.
इर्यःऽइव १२. ३, ११.
इलयत १. १७, ४.
इलयति १०. ७, ३७.
इलयन्ति १०. ७, ३७.
इषः १८. १, ४२; ४, ४६; २०. ८, १; ७१, १४.
इषणयन्त २०. ९१, ८.
इषम् ३. १०, ७; ४. ३९, २; ४; ६; ८; ५. २०, ११; ६. २८, १; ९. १, २०; ५, २४; १८. १, २४; ४, ४; ८८; १९. ४०, ४.
इषवः २. ३, ६; ३. २६, १; २; ३; ४; ५; ६; २७, १; २; ३; ४; ५; ६; ८. ८, २०; ११. ११, १; १७. १, २८; १९. १३, ११.
इषा ३. १९, ८; ७. ८५, १; १९. ५५, १; २; २०. २१, ४; ९.
इषितः ५. १२, ३; ९; ६. २७, १; २; १०. ८, ३५; १२. २, ९; १८. ४, १; २०. ८४, २.
इषितम् ६. ११६, २; १९. ५३, ५; ९.
इषिताः १०. ८, ३३; २०. २४, ३.
इषिरः ६. ६२, १; १८. १, २१; १९. १०, ४.
इषिरम् ५. १, ९.
इषिरस्य २०. १००, ३.
इषिरा १९. ४९, १.
इषिराः ६. ४९, ३; २०. १६, ३.
इषिराम् २०. ६३, ३; १२४, ६.
इषीकाम् १२. २, ५४.
इषीकाम्ऽइव ७. ५८, ४.
इषुऽअग्राणि ११. १२, १६.
इषुऽआयुधे ५. ३१, ७.
इषुऽआसः १५. ५, २; ५; ७; ९; ११; १३; १५.
इषुऽआसम् १५. ५, १; ४; ६; ८; १०; १२; १४.
इषुः ३. २५, १; ३; ५. १८, १५; ७. ५४, २; ११. २, १२; १९. ५५, २.
इषुःऽइव ५. १८, १५.
इषुका १. ३, ९.
इषुऽधिम् ३. २३, २.
इषुऽधौ ४. १०, ६.
इषुऽभृताम् ४. २८, २.
इषुऽभ्यः ३. २७, १; २; ३; ४; ५; ६.
इषुम् १. १३, ४; ३. २५, २; ६. ५७, १;

९०, १; **८.** ८, २०; **११.** १२, १६; **१२.** ४, १७; **१९.** ३४, ३.
इषुऽमतीभ्यः **१२.** ३, ५९.
इषुऽमते **१२.** ३, ५५; ५६; ५७; ६०.
इषुऽमत्यै **१२.** ३, ५८.
इषुऽमन्तम् **४.** २४, ५.
इषुऽहस्तेन **१९.** १३, ३.
इषुऽहस्तैः **१९.** १३, ४.
इषूः **८.** ३, ६; **११.** ८, ९.
इषे **७.** ७७, १.
इषे **२०.** ३६, ५.
इषो इति **४.** ६, ६.
इष्टम् **९.** ५, १३; ८, १; **११.** ९, ९; **१२.** ६, ४; १०, १०; **१९.** ७२, १.
इष्टयः **११.** ९, १९.
इष्टये **७.** ४, १; **२०.** १५, २.
इष्टऽवन्तः **१८.** ३, २०.
इष्टस्य **१८.** १, १९.
इष्टा **५.** ३, ४.
इष्टानि **९.** १४, १६.
इष्टापूर्तम् **२.** १२, ४; **३.** १२, ८; **६.** १२३, २; **१८.** २, ५७.
इष्टापूर्तस्य **३.** २९, १.
इष्टापूर्तेन **१८.** ३, ५८.
इष्टे **७.** १५, ४.
इष्टौ **२०.** ९४, ९.
इष्ट्वा **९.** ९, २; ४; ६; ८; **१२.** २, ५४.
इष्णन् **११.** ७, १.
इष्णानः **२०.** ३५, १२.
इष्णामि **८.** ८, १४; १५.
इष्यति **१८.** १, २२.
इष्यन् **२०.** ३५, १२.
इष्यामि **२०.** १३७, ८.
इष्वा **५.** ५, ४; **१०.** १, २७.
इष्वाः **५.** १४, १२.
इह **१.** १, ३; ५, २; ७, ७; ८, १; ९, ३; १०, ४; १५, २^{३}; ३१, ३; **२.** ५, १; ४; ६, ४; १२, १; २६, १; **३.** ३, १; ६; ४, १; ७; ८, ४; ११, ६; १२, १; २; १३, ७; १४, ४^{२}; ५; ६; १६, ५; १७, २; ७; २०, २; ६^{२}; २४, ३; ५; ७; २८, ३; ४^{३}; ३१, ९; **४.** २१, १; २५, ५; ३१, ५; ३८, १; २; ४; ६^{२}; ७^{२}; **५.** ३, ४; ६; ६, ५; ६; ७; ८, १; ११, १; १२, ८; ९; २०, ११; २५, ७; २६, १; ४; ५; २८, ३; ३०, १; ६; ११; १७; **६.** ११, ३; २७, ३; ३२, ३; ४०, १; ५५, १; ५८, १; ६२, ३; ६३, ३; ७३, १^{२}; ३; ७४, ३; ८४, ४; ८७, २^{३}; ८८, ३; ९७, २; ९८, १; ११४, २; ११७, २; १२१, ३; **७.** २, १^{२}; ४, १; ५, ५^{२}; १०, ३; ११, १; १३, ४^{२}; ४१, २; ५२, ३; ५४, १; ५५, २; ५; ६२, ५; ७; ६९, १; ७७, २; ७८, ४; ८३, १; २; ८७, ३; ८९, १; ९०, १; १०२, १; ११६, १^{२}; **८.** १, १^{२}; ३^{४}; ७; १८; २, ६; ७; ३, ८; ७, ६; ७; १०; **९.** २, ८; ४, ६; २३; १४, ५; १८; **१०.** १, २०; ४, ९; **११.** १, १; ४; १०; १०, ३३; १२, ९; **१२.** २, ८; २१; ३, १२^{२}; १३; ४३; **१३.** १, २; ४; ५^{२}; १०; १७; १८; १९; ३९; **१४.** १, २१; २२; ३२^{२}; २, १५; १८; १९; २४; २५; २९; ३१; ३२; ३७; ३९; ६३; ७१; ७४; **१८.** १, ७; ९; २५; ३९; ४५; ५९^{२}; २, १३; २१; २४; २९; ३७^{२}; ५७; ५९; ३, १;

१४; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४३; ४४; ४५; ६१; ७३; ४, १२; १३; १६^{२}; १७^{२}; १८^{२}; १९^{२}; २०^{२}; २१^{२}; २२^{२}; २३^{२}; २४^{२}; ३८^{२}; ६६; ८७^{२}; **१९.** ६, २; ९, १४^{३}; १०, ६; ४८, ४; ४९, ३; ५२, ४; ५६, ६^{२}; ७२, १; **२०.** ६, ९; २०, ४; २२, ३; २३, ८; २४, ४; २५, ७; ३३, १; २; ५७, ७; ६७, ५; ७७, १; ९२, ८; ९६, १; २; ९७, १; १०१, ३; १३७, २.

इहऽईह **२०.** १२५, २; १४३, ७.

इहऽक्रतुः **१८.** ४, ३८.

इहऽचित्तः **१८.** ४, ३८.

इहऽभोजनौ **१८.** ४, ४९.

इहि **१९.** ४९, ७.

इहि **१.** १, २; **२.** ५, ४; १३, ४; २५, ४; **३.** २, ५^{२}; ४, १; ५; ६; **४.** ८, २; ९, १; १२, ६; १४, ५; १५, ११; ३१, ३; ३२, ३; ५; ६; ७; ३८, ६; **५.** ४, १; ५, ५; ९; ७, ७; २२, २; ३०, ६; ७; **६.** १६, ३; ४५, १^{२}; ६८, १; **७.** ९, १; ९३, १; १२२, १; **८.** १, ८; ९; ११, ४^{४}; १३, १; ५; ९; १३; १४, १; ५; ९; १३; **९.** ५, ८; **१०.** १, ७; १६^{२}; २०; २४; २५; २६; २८; ४, ६; ९, ३; ११; **११.** १, १३^{२}; १२, १८; **१२.** २, १^{२}; २१; ३, १; **१३.** १, २०; **१४.** २, ३४; ३५; **१७.** १, ६^{२}; ७^{२}; **१८.** १, ५४^{२}; २, ११; २१; ६०; ३, २; ८; ५८; ७३; **१९.** ३, १; २; **२०.** ५, ३; ५; ८, २; ६८, ४; ७१, ७; ९६, २४; १२६, २०; २१.

इहो इति **३.** १४, ४.

ई

ईक्षते **९.** ६, ३.

ईक्षन्ते **४.** १४, ४; **१४.** १, ३९.

ईक्षमाणः **९.** १२, २३.

ईक्षमाणा **१२.** ७, ९.

ईक्षयन्तु **४.** १५, २.

ईक्षयस्व **४.** १५, ३.

ईक्षे **१२.** १, ५८.

ईङ्खयन्ति **९.** १५, २७.

ईङ्खयन्तीः **२०.** ९३, ४.

ईजाते इति **१३.** १, ४७; ४९; ५०; ५१.

ईजानः **१८.** ४, १४.

ईजानम् **१८.** ४, १; १०; १२.

ईजानाः **१८.** ४, २.

ईजानानाम् **९.** ५, ८; १२.

ईजिरे **७.** ५, ४.

ईडते **१४.** १, ३७.

ईडते **४.** ३२, २.

ईडानः **५.** २७, ४.

ईडामहे **१४.** २, ३३.

ईडितः **१८.** ३, ४२.

ईडिता **४.** ३१, ४.

ईडे **७.** ५२, ३.

ईडे **४.** २३, ३; **५.** १, ८; **१४.** २, १९.

ईड्यः **२.** २, १; **५.** १२, ३; **६.** ९८, १; ११०, १; **८.** ३, २६; **१९.** ५९, १; **२०.** १०१, ३.

ईड्यम् **१७.** १, १; २; ३; ४; ५.

ईदृक् **४.** २७, ६.

ईदृशे **३.** १, २; **७.** ११४, १; ७.

ईप्सन् **९.** ५, १२.

ईम् **४.** ३०, ४; **९.** १४, ५; १०; १५; १५, १०^{२}; **१८.** १, ७; २०; २, ४; **२०.** ५,

५; १८, २; ३४, ५; ५१, ४; ५३, १; ५४, २[२], ५६, १; ५७, ११; ६८, ७; ७१, ८; ९१, ५; ७; ९२, १४; ९४, ३; ९५, १.

ईमसि १०. ४, ६.

ईमहे २०. ७०, ६.

ईमहे ४. २३, १; ६. ३६, १; १८. ४, ६१; २०. ९, २; १९, ३; ६; २४, ६; ३६, ३; ४९, ५; ५२, ३; ५७, १६; ६३, ७; ८; ९; १०३, ३; १०८, २.

ईयतुः २०. १०५, २.

ईयते १२. १, ५१; २०. ३१, २.

ईयते ४. ३४, ४; १९. ५३, २; ५४, ५.

ईयन्ते ११. १०, २६.

ईयमानः १५. १, १.

ईयमानम् ११. २, १७.

ईयसे ४. १३, ३.

ईयसे ५. ६, ४,

ईयुः १८. १, ४४; ४६; २, ५५.

ईयुः ९. १४, ८.

ईरताम् ३. १९, ६; १८. १, ४४.

ईरते १९. ८, ६.

ईरते ४. २५, ३; १३. २, १; १९. ३८, २; २०. १०, १; ५९, १.

ईरय ५. ३०, १४; ६. ३४, १; ७. १०२, ३; १८. १, २३; २०. ७६, ५.

ईरयत ४. १५, ५.

ईरयन् ४. १५, ११.

ईरयन्ताम् ५. १, ३; ६. ६१, १.

ईरयस्व १४. २, ३८; १७. १, ११.

ईरयामः ५. २९, ५.

ईरयामसि ८. २, ५.

ईरयेथाम् ५. १, ४.

ईर्त्सीः ५. ७, ६.

ईर्मा २०. ९४, ६.

ईर्माभ्याम् १०. १०, २१.

ईर्ष्याम् ६. १८, ३; ७. ४७, १; ७८, ३.

ईर्ष्यायाः ६. १८, १; ७. ४६, १.

ईर्ष्याः ६. १८, २.

ईर्ष्वे १८. ३, २.

ईलते २०. १०२, २.

ईलय ६. १६, ३.

ईलिष्व २०. १०३, १.

ईलेन्यः २०. १०२, १.

ईर्वतः २०. १२, १.

ईर्वते २०. ९०, २.

ईशत ४. २१, ७; ७. ७९, १; १९. ४७, ६[२];

ईशते ५. २१, ७.

ईशते २०. १७, ३.

ईशा ११. १०, १७.

ईशाथे इति ४. २८, १; २; ३; ४; ५; ६.

ईशाथे इति २०. १७, १२; ८७, ७.

ईशानः ३. १५, १; ६. २, ३; ७. १८, १; १९, १; ९. २, ३; ११. ९, १६; ११, ४; १५. १, ५; ५, २; ५; ७; ९; ११; १३; १५[२]; १४, १९; २०. ५, ३; ३५, ६; १२; १५; ६३, ४; ६९, ८; ७०, १४; १३७, ५.

ईशानऽकृत् २०. ३५, ११; १०४, ४.

ईशानम् १५. ५, १४; २०. ६८, १२; १२१, १[२].

ईशानाः १. ५, ४; ४. २७, ४; ५; ११. ११, २६.

ईशानाम् ४. १७, १.

ईशाम् ११. ११, २५[३]; १२, २; १५. १, ५.

ईशिध्वे ४. २७, ६.

ईशिषे २. २८, ३; ६. ७९, ३; २०. ९३, ३; ९४, ५.
ईशीय २०. २७, १; ८२, १.
ईशे २. ३४, १; ३. १५, ३; ४. २, १; ११, ५^{२}; ६. २८, ३; ११. ६, २३; २४; १३. ३, २४.
ईशे ६. ८६, २^{२}; ८. २, २३^{२}; ११. २, २७; २०. १२६, १६^{२}; १७^{२}.
ईश्महे ४. ३८, ७.
ईश्वरः ११. ६, १; १०; १९. ६, ४; ५३, ८.
ईश्वराः ७. १०७, १.
ईषतु ११. ११, २१.
ईषा ८. ८, २३.
ईषाऽयुगेभ्यः २. ८, ४.
ईषिरे ५. १९, ३; १९. २६, २.
ईषे इति ११. ३, ९.
ईर्ष्यन्तम् १८. २, ५३.

उ

उक्तम् १. ३०, २; ४. ३०, ४.
उक्ता १२. १, ५५.
उक्थम् ६. ३५, ३; २०. ६०, ६; ७१, ६; ७७, २; ९१, १.
उक्थऽमदानि ५. २६, ३.
उक्थऽवर्धनः २०. २९, १.
उक्थऽवाहः २०. ३३, १.
उक्थऽशंसः १८. ३, २१; २०. ३७, ९.
उक्था २०. ३७, ९; ६९, ६; ८५, १.
उक्थानि २. १२, २; २०. ४४, २; ९४, ८.
उक्थिनः २०. ५२, २; ५७, १५; ६१, ३.
उक्थे २०. १११, ३.
उक्थेभिः २०. ११, ७; १८, १; २४, ४.
उक्थेषु ६. ३५, २; २०. २३, ४.

उक्थैः ७. ६५, १; १८. १, ४३; ४, ४७; २०. ३५, १३; १४०, ४.
उक्थ्यः ११. ९, १०; १८. १, २२; २०. २५, ६.
उक्थ्यम् ७. ४९, १; ५०, १; १२. २, १०; २०. २५, ३; ३०, ५.
उक्थ्या २०. १४२, ६.
उक्षऽअन्नाय ३. २१, ६; २०. १, ३.
उक्षणः ४. २४, ४; २०. १२६, १३.
उक्षणम् १८. ३, १८.
उक्षणम्ऽइव ३. ११, ८.
उक्षत ५. २८, ४; ७. ७९, २.
उक्षतु १०. ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; १२. १, ७; ९.
उक्षन्तु ३. १२, ४.
उक्षन्तु १८. २, २२.
उक्षमाणा ३. १२, १.
उक्षाणम् ९. १५, २५.
उक्षामि १९. २७, ५.
उक्षिता ५. ५, ८.
उक्ष्णः २०. १२६, १४.
उखम् ११. ३, १८.
उखा १२. ३, २३.
उख्यान् ४. १४, २.
उग्र १. १०, २; ४; ११. २, १०; २१; २०. ७३, २.
उग्रऽआयुधाः ३. १९, ७.
उग्रः २. २९, ४; ३. ४, २; ३; ४; ७; १२, ६; ४. ८, २; ९, ४; १९, ८; ५. २, १; ८, ९; १९, ६; ६. १६, १; ८. ५, २; ९. २, ३; ७; १४; १०. २, ९; ११. १, १५; १२. ७, १०; १३. ३, १९; १५. ५, ९; १८. ३, २३; १९. १३, ५; ७; ३२, १;

३४, ७; ९; ५२, २; ६५, १; **२०.** १४, २; ५३, ३; ५७, १३; ६२, २; ७०, १०; ७६, ३; ८९, ७; १०७, ४.

उग्रऽजितौ **६.** ११८, १.

उग्रऽधन्वा **८.** ६, १८; **१९.** १३, ४.

उग्रऽबाहवः **३.** १९, ७.

उग्रऽबाहुः **४.** २४, २.

उग्रम् **३.** ५, ४; १६, २; **४.** १३, ५; २७, ७; ३०, ३; ३१, ३; ३६, ८; **५.** ३, १०; १७, १; **६.** ५७, २; ९७, ३; ९९, १; **८.** ५, १९; **१०.** ४, ३; ४; ६, ६; ७; ८; ९; १०; **१२.** १, १; **१५.** ५, ८; **१८.** १, ४०; **१९.** १३, ६; १०; ३३, ४; **२०.** ११, ११; ५४, १; ५५, १; ६३, ६; ८०, २; ९२, १९; ९४, ३.

उग्रम्ऽपश्याः **७.** ११४, ६.

उग्रंपश्ये इत्युग्रम्ऽपश्ये **६.** ११८, २.

उग्रंपश्ये इत्युग्रम्ऽपश्ये **६.** ११८, १.

उग्रस्य **१.** १०, १; **६.** ७३, १.

उग्रा **२.** २५, १; **८.** ८, ९; **९.** १, ३; १०; **१९.** १५, ४.

उग्राः **३.** १, २; १९, ७; **५.** २१, ११; **६.** ७४, ३; **८.** ७, ४; १०; **१३.** १, ३; **१९.** ३४, ८.

उग्राभिः **२०.** ७०, १०.

उग्राम् **२०.** २५, ७; ३३, २.

उग्राय **७.** ११४, १.

उग्रासः **२०.** ९४, ३.

उग्रीणाम् **४.** २४, २.

उग्रेण **५.** १३, ३; २३, २.

उग्रैः **५.** १३, १.

उग्रौ **४.** २८, ३; ६; **८.** ६, २०; **११.** २, १४.

उग्रौ **४.** २८, ७.

उच्चा **१३.** २, ३६.

उच्चैः **४.** १, ३.

उच्चैःऽघोषः **५.** २०, १.

उच्चैःऽघोषा **९.** १, ८.

उच्यतु **२.** १४, ३; **६.** २६, ३.

उच्यते **९.** ६, २; **१०.** २, २८; ३०.

उच्यते **३.** १३, ४; **४.** २१, ६; **५.** १८, १४; **६.** ४३, १; २; **९.** २, ५; **१०.** २, २२; २३; **११.** ६, १३[२]; १५; १०, ३४; **१३.** ५, ३; ४; ५.

उच्यसे **४.** ९, १०; **१२.** ४, ४; १०, ७.

उच्यसे **१९.** ४४, १.

उच्येते इति **१९.** ६, ५.

उच्छतु **२.** ८, २[२]; ३; ४; ५; **३.** ७, ७; **६.** ८३, १; **७.** ७२, १; **८.** ४, २३; **१४.** २, ४८; **१६.** ६, २.

उच्छन्तु **२.** ८, २; **३.** १६, ७.

उच्छेत् **११.** ६, २१.

उच्छोचनऽप्रशोचनौ **७.** १००, १.

उत् **१.** १०, १; २२, १; २९, ५[२]; **२.** ३, ४; ६, २; ८, १; ९, १; २; १०, ६; **३.** ४, १; ९, ५; ६; ११, ८; १२, २; १३, ४; १६, ३; १७, ३; ६; १९, ३; ६[३]; २४, ४; २५, १; ३१, १०[२]; ११; **४.** १, ३; ३, १; ४, २[४]; ४; १२, ६; १३, १; १४, ७; ९; १५, ३; ५[२]; १६; २०, ८; २७, ४; **५.** ९, ८[६]; १३, २; ३; १४, ११; २०, ८; ११; २३, ६; ३०, ११; **६.** ५, १; २२, १; ३६, २; ५१, २; ५२, १; ७६, १; १०२, ३; १०९, ३; ११२, २; ११९, १; १२०, १; १२१, २; ३;

१२७, १; १३०, ४^{३}; १३४, २; १४२, १; २; **७.** ३०, २; ५२, ४; ५४, २; ५५, ७; ७५, १; ८५, १; ८८, ३; १००, १; २; १०८, १; ११८, १; **८.** १, २^{४}; ३; ४; १६^{२}; १७^{४}; १८; १९; २, ८; ९; १५; २३; ४, ४; ७, २१; २८; ९, १; ६; १४, १; ५; ९; १३; १०, २; ४; ६; ८; १०; १२; ११, १; १२, १; ३; ५; ७; १३, १; ५; ९; १३; **९.** २, २; ५, ६; ७, २; १०, २; ५; ७; ८; १४, १७; २१; १५, १२; **१०.** १, १७; २०; २९; ३१; ७, ४३; ८, २९; १०, १९; २२; **११.** १, ७; ९; १४; ६, २१; ७, ५; ११, २; ३; ५; ६; १२; १३; १८; २१^{२}; २६; १२, १; ५; **१२.** १, ३०; ३९; २, ५; २६; २७^{२}; ३, १५; २९; ३०; ३५; ३६; ४६; ५३; ४, २४; ११, ११; **१३.** १, २; २३; ३६; ४१; ४३; २, १; ९; १६; २०; ३५; ३, १; २; ३; ४; ५; ६; ७; ८; ९^{२}; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३^{२}; २४; २५; **१४.** १, ३८; ३९; ५७; ५९; २, १६; १९^{२}; ३३; ३६; **१५.** २, १; ९; १५; २१; १०, ३; **१७.** १, ६^{२}; ७^{२}; २४; **१८.** १, १०; २३; ४४^{३}; ६१; २, २२; २३; ४३; ३, २; ८; ५०; ५२; ६५; ४, ६९; **१९.** १०, ८; १३, १०; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २७, ८; ५४, १; ६३, १; **२०.** ७, १; १०, १; १२, १; १६, ७; १७, ९; ११; २०, ३; २८, २; २९, ३; ३९, ३; ४७, १३; १७; ५७, ६; ५९, १; ३; ६४, ५; ७१, १०; ७३, २; ५; ८८, ५; ९१, ३; ४; ८; ९२, ४; ९३, १; ६; ९४, ११; १०७, १४; १३७, २.

उत **१.** ४, ४; ८, ३; ९, १; २; ४^{२}; ११, २; १२, ३; १५, २; १७, २; १८, ४; १९, ३; २२, ३; २८, ४; ३०, १^{२}; ४; ३१, ४; ३५, ३; **२.** १, ३; ९, ३; ४; १२, १; २८, ३; २९, ३; ३२, ४; ३४, १; **३.** ५, ५; ६, ८; ७, ७; १०, ९; ११, १; १३, ६; १४, ४; ५; १६, १; ४^{४}; १९, ४; २०, ३; ८; २१, ३; २८, २; ३०, ३; **४.** २, ७; ८; ३, २; ४, ५^{२}; ६, ३; ५; ६; ७, ६; ८, ५; ९, ३^{२}; ६; १०, ३; ११, १; १३, १^{२}; १४, ५; १५, ७; ९; १६, ३^{३}; ४; १९, ३; २०, ४; ८^{२}; २१, १; २२, ५; २५, ५; २८, २; ५; २९, ५; ६; ३०, १; ३; ६; ७; ३२, ६; ३७, ५; **५.** १, ७^{२}; ८; ७, ८; १२, २; १३, १; १७, ८; १८, ९; १०; २१, ११; २२, १३; २३, ७; ८; ११; ३०, १२; ३१, ५; **६.** ३, १; ३; १८, १; २; २१, ३; २७, ३; ३८, १; ४१, १; ५९, २; ६०, १; ३; ६१, १; २; ३; ७१, १; ३; ९२, २; ९३, २; ९५, ३; ९६, २; ९८, ३; १०९, १; ११३, २; ११९, १; १२०, १; १२६, १; १४१, ३; **७.** ५, ५^{२}; १२, १; २७, ८^{२}; ३६, २; ३; ३९, ३; ५१, २; ५२, ५; ६; ५३, १^{२}; ५८, ६; ७७, ७; ७८, २; ८५, १; १००, ३; १०२, १; ११६, १; ११७, २; **८.** ३, ३; ५^{२}; ७^{२}; १९; २०; ४, २२^{२}; २४; ५, ६^{२}; ६, १; ५; ६; १७; २१; ७, १; २७; २८; ८, १४; ९, २४; **९.** १, २; २, १४; २४; ३, १; ५, १५; १५, ४; **१०.** १, २७^{२};

३, १३; १४; १५; ४, ५; ७, १९; ३२; ८, १२; १७; २३; २५; २७; २८[४]; १०, १; ३४; ११. १, १८; ३४; २, ४; १५; २९[२]; ६, ७; १६; ७, ४; ८, १; ३; ८; १७; २१; ११, १५; २१; २४; १२. १, ३; २५; २८; ३२; २, १७; ३, ११; १२; १६; २७[२]; ४, १८; ५०; १३. १, १५; ३८; २, २६[२]; ३, ७; १४. १, १०; २८; ४४[२]; २, ४८; ६९; १७. १, १२; २९; १८. १, ५; ४८[२]; २, ३३; ४९; ३, ५३; ५५; १९. १, २; ६, ४; ११, ४; ६; १५, ३; २२, २१; २३, ३०; ३२, ४; ३५, ४; ४४, ६; ४८, ४; ५०, ५; ५३, ५; ५६, ४; ६२, १[२]; २०. ८, १; ११, २; ८; ९[२]; १७, ३; ५; ११; १२; १९, २; २१, ८; २३, ७; २९, १; ३१, ५; ३४, ५; ३७, ५; ५४, १; ५६, १; ६०, १; ६७, २[२]; ४; ६८, ५; ६; ८१, १; ८७, २[२]; ७; ८९, ९; ११[२]; ९१, ३; ९२, ५; २०; ९४, ११; ९६, ६; १०६, १; ११३, २; १२५, ३; १२६, ९; १४; १४०, ५; १४१, १[२]; १४३, ९.
उतऽइव ६. २०, १; १२. ३, २७.
उत्ऽ अकल्पयन् १२. ४, ४१.
उत्ऽअगाः २०. ११२, १.
उत्ऽअभराम १९. ७२, १.
उतम् १४. २, ५१.
उत्ऽअयंत् ८. ४, ३.
उत्ऽअयनम् ५. ३०, ७.
उत्ऽअवन्तौ ७. १००, २.
उत्ऽअवस्यति ९. ११, ६.
उत्ऽअस्थुः १. १६, १.
उत्ऽआकुरुत १२. ४, ४१.
उत्ऽआगाम् १४. २, ४४.
उत्ऽआचरत् ४. ५, १.
उत्ऽआजत् २०. ३४, ३.
उत्ऽआनट् ६. ७७, २[२].
उत्ऽआयच्छतु ५. ३०, १५.
उत्ऽआयते १७. १, २२.
उत्ऽआयन् ११. १, ३७.
उत्ऽआय्य॒म् १०. १, ७.
उत्ऽआराः ११. १२, १.
उत्ऽआराः ११. ११, १६.
उत्ऽआराणाम् ११. ११, ६.
उत्ऽआरान् ६. ११३, २; ११. ११, १; १५; २२; २४.
उत्ऽआरे ४. ११, ३.
उत्ऽईतयः १०. २, १०.
उत्ऽईताय १७. १, २२.
उत्ऽईते ४. २५, ३.
उत्ऽईतौ ३. १६, ४; ७. ५, ३.
उत्ऽइत्य १८. २, ४७.
उत्ऽईव ५. १९, १; ६. ७१, २.
उत्ऽईरते १. २०, २; ६. ९९, २; २०. ५६, ३.
उत्ऽईराणाः १२. १, २८.
उत्ऽउह्य १९. २५, १.
उत्ऽऋचि ६. ४८, १; २; ३; २०. २१, ११.
उत्ऽएत ११. ८, १८.
उत्ऽएति १०. ८, १६; १३. ४, ७.
उत्ऽएत्य १२. ४, ४१.
उत्ऽएहि ५. ३०, ११; ११. १, २१; १३. १, १.
उतो इति ४. १६, ३; १९, १[३]; १०. ७, २१; ८, २९; १८. १, ४८; १९. ३५, ५; ४७, ३; २०. ७२, ३; ११२, २.

उत्ऽकूलम् १९. २५, १.
उत्ऽखिदन् ४. ११, १०.
उत्ऽखिदन्ती १२. ७, ८.
उत्ऽखिदेत् ११. ६, २१.
उत्ऽगीथः ११. ९, ५; १५. ३, ८.
उत्ऽगृह्णन् ९. १०, ७.
उत्ऽचरन् ११. ६, २१.
उत्ऽचरन्तम् ६. ६२, ३; ८. ४, २४.
उत्ऽचरातः २०. १६, १०.
उत्ऽजिहानाः १३. २, ४६.
उत्ऽजेषे ४. १७, १.
उत्ऽततम् २. ७, ३; ७. ९५, ३.
उत्तभिता १४. १, १[२].
उत्ऽतमः ३. ५, २; ५. ४, ९[२]; ६. १५, १; २; ३[२]; ८. ५, ११; १९. ३९, ४.
उत्ऽतमम् १. ९, २; ४; २. ३, २; ८, १; ३. ७, ४; ४. १४, ६; ९; २२, ५; ५. १३, २; ६. ६३, ३; ८४, ४; ७. ५५, ७[२]; ८८, ३; ११. १, ४; ३०; ३७; १२. ३, ४५; १८. ३, ६४; ४, ६९.
उत्ऽतमा ६. २१, १.
उत्ऽतमाः ६. १२१, १; ७. ८८, ४.
उत्ऽतमानि ५. ४, ८; ७. ७७, १०.
उत्ऽतमाम् ९. ५, २९; १५. ६, ७; १८. ३, ६४.
उत्ऽतमे ११. ६, ११; १८; १२. १, ८.
उत्ऽतमेन १. ९, ३.
उत्ऽतमेभ्यः १९. २२, १२.
उत्तरः ४. २२, ६; ५. २८, १०; ११. १०, १८; १२. १, ५४;
उत्ऽतरः २०. २९, ५; १२६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३;
उत्तरः ३. ५, ५.
उत्ऽतरः १९. ४६. ७.
उत्तरतः ४. ४०, ४; १८. ४, ९.
उत्तरऽत्वे ३. ८, ३.
उत्तरऽद्रौ ६. ४९, २.
उत्तरम् ४. १४, ८; ११. ७, ६; १२. ३, १०;
उत्ऽतरम् २. २७, ७; ४. ३१, ६; ६. ५४, १; २; ७. २७, १; १०. ६, ३१; ७, ३; ११; १८. ४, ५१.
उत्ऽतरम् ६. ५, १.
उत्तरऽवत् १२. ३, १०; ४७;
उत्तरऽवन्तम् ४. २२, ५; १०. ८, २२.
उत्ऽतरस्मात् ७. ५३, १; २०. १७, ११; ८९, ११; ९४, ११.
उत्तरस्मिन् ११. २, २५.
उत्ऽतरस्मिन् १. ९, १;
उत्तरस्याम् ४. १४, ८.
उत्तरऽहनुः ९. १२, २.
उत्तरा ६. १६, ४.
उत्ऽतरा ३. १८, ४[२]; १०. २, २४; २५; १८. १, ११.
उत्ऽतराः १९. ७, ४.
उत्ऽतराणि २०. ९१, १०.
उत्तरात् ६. ४०, ३; ८. ३, २०; ५, १७; १०. ९, ८; ११. २, ४; ८, १८; १२. १, ३२; ३, २४; १८. ४, ११; १९. १६, १; २७, १४; ४८, ४.
उत्ऽतरात् १९. १५, ५.
उत्ऽतराभ्यः ३. १८, ४.
उत्तराम् ६. ११८, ३; ८. २, १५.

उत्तराम्ऽउत्तराम् ३. १०, १; १७, ४; १२. १, ३३.
उत्ऽतरे १९. १३, ११; २०. ७०, १३.
उत्ऽतरे ३. १८, ४.
उत्तरेणऽइव १०. ८, ४१.
उत्तरेभ्यः ६. १३४, २.
उत्ऽतरेभ्यः १९. २२, १३.
उत्ऽतरौ १०. २, २.
उत्तस्थिऽवांसः ६. ९३, १.
उत्तानऽपर्णे ३. १८, २.
उत्तानयोः ९. १५, १२.
उत्तानऽशीवरीः ३. २१, १०.
उत्तानाः १२. १, ३४.
उत्तानायाम् ९. १४, १४.
उत्ऽतिरः १९. ३२, १.
उत्ऽतिरन् ६. ३६, २.
उत्ऽतिष्ठन् २०. ४२, ३.
उत्ऽतुदः ३. २५, १.
उत्थातुः ९. ४, १४.
उत्थाय १९. ३१, १२.
उत्थितः ६. ४३, २; ९. १२, १९.
उत्थितम् ३. १५, ४.
उत्थिता ६. ४४, ३.
उत्ऽनयन्तीम् ८. ७, ६.
उत्ऽनिनाय १३. २, ४.
उत्ऽपतन्तम् १९. ६५, १.
उत्ऽपतिष्यन् १८. ४, १४.
उत्ऽपाताः १९. ९, ७.
उत्ऽपारणस्य ५. ३०, १२.
उत्ऽपिपानः ५. २०, ७.
उत्ऽपिपानम् १३. १, ३१.
उत्ऽभरन्ती ११. १, ९.
उत्ऽभित् ५. २०, ११.
उत्ऽभिन्दतीम् ४. ३८, १.
उत्ऽभिन्नम् १०. ५, ३६; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; ९, १.
उत्ऽभु ९. २, १६.
उत्ऽभृतम् २. ३, ५; ६. १२५, २; ७. ४६, १.
उत्ऽभृता १. २४, ४.
उत्ऽभ्यसाः ११. ११, १७.
उत्ऽभ्वीः १८. ४, २६; ४३.
उत्ऽमज्य १०. ४, ४.
उत्ऽमत्तम् ६. १११, ३.
उत्ऽमदितम् ६. १११, ३.
उत्ऽममार्ज ८. ६, १.
उत्ऽमुञ्चन्तीः ८. ७, १०.
उत्ऽमृजानः १८. ३, ७३.
उत्ऽयतः ४. २४, ६; ८. ८, १२; १२. ३, १८.
उत्ऽयतम् २०. ९२, ६.
उत्ऽयतानि ५. ११, ९.
उत्ऽयते १७. १, २२.
उत्ऽयत्य ८. ८, १२.
उत्ऽयन् २. ३२, १; ७. १४, १; २; ९. २, १५; ५, ३५; १०, ४; १३, २२; १२. १, १५; १३. १, ३२; २, १०; २८; ३४; ३, १३; १७. १, ३०; १९. २८, ४; २०. १०७, १३.
उत्ऽयन्तम् ६. ७६, २; ९. ५, ३५.
उत्ऽयमीयसी २०. १२६, ६.
उत्ऽयानम् ८. १, ६.
उत्ऽयुगम् ५. २२, ११.

उत्ऽयुजे ६. ७०, २.

उत्ऽयुतम् ६. १११, २.

उत्ऽलुप्तः १९. ३३, २; ४६, ६.

उत्ऽलुप्तम् ५. २८, १४.

उत्ऽवतः १२. १, २.

उत्ऽवहः १९. २५, १.

उत्ऽवाचनम् ५. ८, ८.

उत्ऽवीता १२. ७, ७.

उत्ऽवेपमानाः ५. २१, २.

उत्ऽवेपयति ९. १३, ६.

उत्ऽशिषाते २. ३१, ३.

उत्ऽशिष्टः ११. ९, १५; १६.

उत्ऽशिष्टम् ९. १०, ९.

उत्ऽशिष्टाम् ११. ९, ११; २३; २४; २५; २६; २७.

उत्ऽशिष्टे ११. ३, २१; ९, १[३]; २[२]; ३[२]; ४; ५[२]; ६; ७; ८; ९; १०; १२; १३; १४[२]; १७; १८; १९; २०; २१; २२.

उत्ऽशोचनौ ७. १००, १.

उत्ऽशोचयन् ५. २२, २.

उत्ऽश्रितम् १३. ४, ३.

उत्ऽश्रेयः १९. १४, १.

उत्ऽश्लङ्क्ौ १०. २, १.

उत्ऽश्वञ्चमाना १८. ३, ५१.

उत्ऽश्वासे १८. ३, १८.

उत्सः ६. १०६, १; २०. ११८, २.

उत्ऽसंन्नाः ११. ९, ८.

उत्सम् ३. २४, ४; ४. २७, २; ३१, ५; १७. १, १५; १८. ४, ३५; ३६.

उत्साः ४. १५, ७; ९.

उत्सासः १. १५, ३.

उत्सितः ६. ११२, ३.

उत्सिताः ६. ११२, २.

उत्ऽसिसृप्सतः २०. २९, ४.

उत्स्याः १९. २, १.

उत्ऽहर्षिणम् ८. ६, १७.

उत्ऽहृत्य १९. ६८, १.

उदक् २०. १२०, १.

उदकऽआत्मानः ८. ७, ९.

उदकम् ३. १३, ४; ५. १४, १३; १९, ८; ६. १००, २; १२९, ४; ७. ७७, ११; ९. ५, ५; ६, ४; ९, ९; १०; १०, ८; १४, ५; १५, २०; १०. ८, १४; १२. ३, ३०; १५. ११, २; ४; १३, १३.

उदकस्य १. १५, ४.

उदके ४. १६, ३.

उदकेन ४. ३४, ६; ७; ६. ६८, १.

उदकेषु ९. २, ६.

उदक्तः ८. ३, १९; ४, १९.

उदङ् ५. ४, ८; ९. १२, २१.

उदञ्चः २०. १२६, २२.

उदऽधिम् ४. १५, ६; ११.

उदऽधेः २०. ९१, ५.

उदधेःऽइव १. ३, ८.

उदनि २०. १६, ८.

उदन्ऽवती १८. २, ४८.

उदन्वतीः १९. ९, १.

उदऽपूः १८. ३, ३७.

उदऽप्रुतः ६. २२, ३; १८. २, २२; २०. १६, १.

उदप्रुतम्ऽइव १०. ४, ३; ४.

उदऽभिः २०. १००, १.

उदरऽदारः ११. ४, ११.

उदरम् ४. १६, ७; ३४, १; ९. ३, १५;

१२, १६; १०. ७, ३२; १०, २२; ११. ७, २५; १५. १, ७; २०. १२६, २३.
उदरात् २. ३३, ४; ९. १३, ९; ११; १२; १०. १०, २१; २०. ९६, २०.
उदराय ११. २, ६.
उदरे ११. ७, ३.
उदरेण ११. ४, ११[२].
उदऽवाहाः १८. २, २२.
उदऽहार्यम् १०. ८, १४.
उदाऽइव २०. १००, १.
उदारथिम् ४. ७, ३.
उदिता ७. ७०, २.
उदीचः २०. १२५, १.
उदीची ३. २७, ४; १२. ३, १०.
उदीचीः १२. १, ३१; २, ४१.
उदीचीनैः १२. २, २९.
उदीचीम् १५. २, २१; १४, ७.
उदीच्यम् ४. ७, २.
उदीच्याः ४. ४०, ४; ५. १०, ४; ६. ९८, ३; ९. ३, २८; १५. ४, १०; १२; ५, ८; ९; १८. ३, २८; १९. १७, ७; १८, ७.
उदीच्याम् ३. २६, ४; १५. २, २४; १८. ३, ३३.
उदीच्यै १२. ३, ५८.
उदुम्बलम् ८. ६, १७.
उदुम्बलौ १८. २, १३.
उदेयम् ३. २०, १०; १६. २, २.
उद्धरन् २०. १६, ४.
उद्धिः ८. ८, २२.
उद्धिता ९. ३, ६; १९. ४२, २.
उद्धिताः १८. २, ३४.
उद्धृता १२. ८, ७.
उद्धृतेषु १५. १२, २.
उद्गः ७. १९, १; २०. १६, ५.
उद्गा ३. १२, ४; ७. ४७, १.
उद्गाऽइव २०. १६, ४.
उद्यतीम्ऽउद्यतीम् ९. ५, ३५.
उद्यमानम् ७. ६८, १.
उद्भ्रियमाणा १२. ८, ७.
उन्दन्तु ६. ६८, १; २.
उन्दते ५. १९, १४.
उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने ५. ३०, २; ३; ४.
उप १. १, ४; ४, २; ३; ७, ५; १६, २; २८, १; ३३, ४; २. १, ४; ५, २; ३. ४, ५; ८, ४; १०, ११; १२, १; ९; १४, ६; १५, ७; १७, ७; १८, ६; २९, २; ४; ५; ६[२]; ४. ११, ११; १५, ४; १८, २; २१, २; ४; २४, १; २५, ७; ३०, ४; ७; ३१, १; ३२, ६; ३४, ३; ५[२]; ६[२]; ७[२]; ३६, ८; ५. ८, ३; १०, ८[२]; ११, २; ६; १७, ११; १९, ९; २०, ४; २२, ११; ३०, १५; ६. २३, १; ३२, १; ३; ३५, १; २; ३७, १; ४२, २; ४९, ३; ५७, २; ६७, ३; ११४, ३; १२६, १; ७. १३, १; २८, १; ३३, १; ६०, १; ६२, ३; ६३, २; ७७, ६; ७; ९; ७८, ४; ७९, २; १०२, १; ११५, ३; ८. २, १; ३, १; २; ३; ६, ३; ८, २१; ११, २; ३; १२, ८[२]; १३, १; ४; ५; ८; ९; १२; १३; १६; १४, १; ४; ५; ८; ९; १२; १३; १६; ९. १, २०; ३, २३; ४, २३[४]; ५, १५; ३०; ६, ४; ७, ३; १०, ९; १२, २६; १४, ४; १५, ४; १०. १, १०; ४, १४; ५, ६; ७, ४४; १०, २६; ३१; ३२; ३४;

११. १, २३; २५; ३४; २, १७; ६, ११; १२; ७, ९; १०, ५; ६; १७; १२, २; **१२.** १, ४६; ३, ३; १९[२]; ३४; ३७; ३८; ४०; ५३; ४, २; ३५; ७, १६; १०, ६; **१३.** १, १४; २, ३७; ४, ६; ६, ६; ८, २; ५; ६; ९, १; २; ३; **१४.** १, १५; २, २३; २४; २५; ३९; ५१; ६३; **१६.** १, १२; ४, ७; **१८.** १, ११; २, ४; १०; १४; २१[२]; २३; ३७; ५३; ६०; ३, १; २; ५[२]; ४९; ५१; ६६; ४, ८; ३२; ३३; ३६; ४०[२]; **१९.** ३, ४; ४, ३; १५, २; ४; ३१, ७; १०; ३४, ८; ४३, ७; ५२, ४; ५६, ३; ५८, २[२]; ३; ६९, २; **२०.** ३, २; ४, १; १२, ३; ७; १४, २; १९, ५; २१, ७; २४, १; २५, २; २६, २; २९, २; ३७, ११[२]; ३८, २; ४७, ८; ५६, ५; ५७, २; ५८, २; ६२, २; ६६, २; ६८, २; ७६, ३; ७७, १; ७८, २; ८४, २; ३; ८५, ४; ८६, १; ८९, २; ९२, १०; १४; ९३, ४; १००, १; १०४, ३; १०८, ३; १२६, २०; १४३, ४; ९.
उ॒प॒ऽअं॒शु **४.** ३२, ७.
उ॒प॒ऽअति॑ष्ठः **१०.** १०, ९.
उ॒प॒ऽअय॑ति **१९.** ४९, १०.
उ॒प॒ऽअय॑सि **१९.** ५०, ६.
उ॒प॒ऽअव॑सृज **५.** १२, १०.
उ॒प॒ऽअवै॑ति **९.** ११, ५.
उ॒प॒ऽआकृ॑तम् **२.** ३४, २.
उ॒प॒ऽआग॑हि **७.** ५०, २.
उ॒प॒ऽआ॒न॒सा॒त् **२.** १४, २.
उ॒प॒ऽआ॒य॒तीम् **३.** १०, २.
उ॒प॒ऽआय॑सि **१.** ३४, २; **३.** २५, ५; **६.** ९, २; ४२, ३; ४३, ३.
उ॒प॒ऽआ॒रि॒म **६.** ४५, २; ९६, ३; **७.** १११, १.
उ॒प॒ऽआ॒वृत॑ः **६.** ७७, ३.
उ॒प॒ऽआस॑ते **४.** २, १; **५.** १७, १७; **६.** ६४, १; **१०.** ६, ३१; ७, २१; २४; **१३.** ३, २४.
उ॒प॒ऽआसा॑तै **१०.** ८, २२.
उ॒प॒ऽआस्म॑हे **३.** १०, ३.
उ॒प॒ऽआहृ॑तम् **१०.** १, १९.
उ॒प॒ऽउ॒त्तमे॑भ्यः **१९.** २२, ११.
उ॒प॒ऽउ॒दैति॑ **९.** ११, ५.
उ॒प॒ऽऊ॒चि॒रे **५.** ८, ६; **११.** १२, १७.
उ॒प॒ऽऊ॒हः **३.** २४, ७.
उ॒प॒ऽऋ॒षन्ति॑ **९.** १३, १४; १५; १६.
उ॒प॒ऽएत॑न **३.** १४, ३.
उ॒प॒ऽए॒यि॒म **१०.** १, १०.
उ॒प॒ऽएष॑न्तम् **८.** ६, १७.
उ॒प॒ऽएतु॑ **७.** ६८, १.
उ॒प॒ऽएमि॑ **६.** ११८, ३.
उप॑ऽक्रस **६.** ५०, २.
उप॑ऽग॒न्त॒वै **२०.** ९६, ५.
उ॒प॒ऽज॒ग्मुष॑ः **२०.** २१, ९.
उ॒प॒ऽजा **११.** १, १९.
उ॒प॒ऽजिघ्र॑ति **१२.** ४, ५.
उ॒प॒ऽजीका॑ः **२.** ३, ४.
उ॒प॒ऽजी॒का॒ः **६.** १००. २.
उ॒प॒ऽजी॒व॒नीय॑ः **८.** १३, ४; ८; १२; १६; १४, ४; ८; १२; १६.
उ॒प॒ऽजीव॑न्ति **१०.** ६, ३२.
उ॒प॒ऽजी॒वाः **१९.** ६९, २.
उ॒प॒ऽजीवे॑म **८.** ११, २.
उ॒प॒ऽत॒प्याम॑हे **७.** ६३, १.
उ॒प॒ऽतिष्ठ॑न्ति **१७.** १, ८.
उ॒प॒ऽतिष्ठ॑न्ती **१२.** ७. १३.

उपऽतिष्ठ॑न्ते ७. ४१, १; ८. ९, ८.
उपऽतिष्ठ॑मानः १३. ३, २५.
उपऽतिष्ठ॑मानाम् ८. ९, ८.
उप॑ऽतृण्य ५. १३, ९.
उपऽदद्य॑ १०. ८, १८; १३. २, ३८; ३, १४.
उपऽदान १९. ३४, ८.
उपऽदेश्य॒म् ११. १०, २३.
उपऽद्रष्टा ११. ५, ९.
उपऽधाने॑ १४. २, ६५.
उपऽधिः ६. ७०, ३.
उपऽध्मानी॑ ८. ८, २.
उपऽनय॑मानः ११. ७, ३.
उपऽनाहः ९. ४, ५.
उपऽनिसे॑दुः १९. ४१, १.
उपऽपक्ष्याः॑ ७. ८०, २.
उपऽपर्चन ९. ४, २३.
उपऽपृञ्च॑ती १८. ४, ५०.
उपऽप्रता॑र्य २. ३६, ५.
उपऽप्रय॑न्ति १२. ४, ३१.
उपऽप्रव॑द ४. १५, १४.
उप॑ऽबद्धान् १. ७, ७.
उपऽबर्ह॑णम् ९. ५, २९; १४. १, ६; १५. ३, ७.
उपऽबर्ह॑णे १२. २, १९; २०.
उप॑ब्दे २. २४, ६.
उपब्दैः ८. ४, १७.
उपऽभृत् १८. ४, ५; ६.
उपऽमम् २०. ३५, ३; ७६, ३.
उपमस्य ५. १, ६.
उपऽमा २०. ९२, १०.
उपऽमाः ४. १, १; ५. ६, १.
उपऽमाना॑म् २०. ११३, २.
उपऽमाम् १८. ३, ६५.
उप॑ऽमास्यम् ८. १२, ४.
उपऽमिता॑म् ९. ३, १.
उपऽयासि॑ १८. १, २२.
उप॑ऽयुक्तम् ४. २३, ३.
उप॑रः ६. ४९, २.
उप॑रस्य ६. ४९, ३; १८. ३, २३; ४, ४.
उपरि॑ ८. ९, ६; १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५.
उपरि॑ऽशयनम् ९. ६, ९.
उपरि॑ष्टात् ४. ४०, ७; ८. ८, १३.
उपरि॑ऽस्पृशः ५. ३, १०.
उप॑रे ९. १४, १२; २०. ९४, ७.
उपऽलिप्स॑मानाः ६. ११८, १.
उपऽवद॑ति १५. २, ३; ११; १७; २३.
उप॑ऽवन्द्यः १८. ४, ६५.
उपऽवाकम् ९. १४, ८.
उपऽवाम् १२. १, ५१.
उपऽवास॑ने १४. २, ४९; ६५.
उपऽविश्य॑ १४. २, २३.
उपऽशृ॒णुयात् १२. ४, २७.
उपऽशोकि॑म ६. ११४, २.
उप॑ऽश्रुतिः १६. २, ५.
उपऽश्रुत्य॑ १२. ४, २८.
उप॑ऽश्रुत्या २. १६, २.
उपऽश्रोता २०. १२, १.
उपऽश्वसे ११. १, १२.
उपऽसंन॑मन्तु १९. ४१, १.
उपऽसंप॑रानयात् १८. ४, ५०.
उपऽसंय॑न्तु ३. ८, ४.
उपऽसंया॑त ६. ७३, १.
उपऽसंव्य॑यस्व २. १३, ३; १९. २४, ५.
उपऽसत्ता ७. ८७, ३.
उपऽसत्ता॑रः २. ६, २; ३. १२, ६.

उपऽसदः ६. १४२, ३; ९. १२, ६; १५. ३, १०; ११.
उपऽसद्यः ३. ४, १; ५. ३०, ११; ६. ९८, १.
उपऽसर्पतः ७. ५८, ५.
उपऽसिच्य ९. ९, १; ३; ५; ७; ९; १०.
उपऽसीदन्ति ९. १, ९.
उपऽसीदान् ११. १, २६; ३२.
उपऽसेचनम् ११. ३, १३.
उपऽस्तयः ६. १५, १.
उपऽस्तरणम् ५. १९, १२.
उपऽस्तरे १४. २, २१.
उपऽस्तिः ६. १५, १.
उपऽस्तीन् ३. ५, ६; ७.
उर्पऽस्तुतः १९. ५, १; २०. ३०, ५.
उपऽस्तृणन्ति ९. ६, ८.
उपऽस्तृणीथन १४. २, २२.
उपऽस्थम् १३. १, ४.
उपऽस्थाः १२. १, ६२.
उपऽस्थात् ३. ११, २; ७. ५५, ३; १४. २, २५; २०. ९६, ७.
उपऽस्थे २. २८, १; ४; २९, ४; ७. ७, २; ८. ४, ९; १३. १, ३८; १४. १, २; ४७; १८. ३, ४३; ६५; २०. १२३, २; १३७, ९.
उपऽहत्तुम् १८. १, ४०.
उपऽहत्याम् ५. ४, १०.
उपऽहरति ९. ७, १०; ११; १२; ९, १; ३; ५; ७; ९; १०.
उपऽहव्यम् ११. ९, १५.
उपऽहस्वानः २०. २२, २.
उर्पऽहूतः १. १, ४; ७. ६२, ५; ९. ११, ७[2]; ८[2]; ९[2]; १०[2]; ११[2]; १२[2]; १६. २, ३[2]; १९. ४०, २.
उर्पऽहूताः ६. १२२, ४; ७. ६२, ४; ५[2]; १८. ३, ४५.
उर्पऽहूतौ ६. १४०, ३.
उर्पऽहृता १२. ८, ८.
उपऽह्रियमाणा १२. ८, ८.
उपऽह्वरे २०. २२, ६; ९२, ३; १३७, ८.
उपाके इति ५. १२, ६; २७, ८.
उपो इति १३. ७, १६; १७; २०. ३५, १४.
उप्ताः ८. ८, १६.
उब्ज ८. ८, ६; ११. १, ६; ७.
उब्जतम् ८. ४, १.
उब्जतु ९. ३, १८.
उब्जन्तः ८. ८, १३.
उभयः ११. ९, ११.
उभयऽद्युः १. २५, ४; ७. १२१, २; ८. १२, ८.
उभयम् ४. ३१, ७; २०. ११३, १.
उभयम्ऽकरम् २०. ८५, २.
उभयाः २०. ३४, ८.
उभयादतः १९. ६, १२.
उभयादति ५. ३१, ३.
उभयादम् ५. १९, २.
उभयान् १२. २, ४४; ३, ६; १८. ४, ३९.
उभयानि ७. ११४, २.
उभयाविन् ८. ३, ३.
उभयाविनम् ५. २५, ९; २०. ८५, २.
उभयाहस्त्या २०. ५६, ४.
उभयीः ८. ५, ९.
उभये ७. ८४, २; ८. ११, २; १२. १, ४७.
उभयेन १२. ४, १८.
उभयेषु २०. १४३, ६.
उभयोः ७. ८०, ४; १०. ४, १०; १५; १९. ३८, ३.

उभा ३. ४, ४; ४. ३०, १²; ५. ३, ९; २५, ३; ७. ४५, १; ११५, १; ८. २, १५; ३, ३; ६, ४; १०. ४, १६; ११. ८, ५; १३. २, १०; ३०; १४. १, ९; ५४; २, १३; १८. १, ५४; २०. १२५, ५; १२६, १४.
उभाभ्याम् ६. १९, ३; ७. ५८, ८; ८. २, २०; ११. २, १६.
उभे इति १. १, ३; २. १०, १; २; ३; ४; ५; ६; ७; ८; ३. ४, ५; १८, ५; ४. ९, १०; ५. १८, ५; ३०, २; ३; ४; ६. १, ३; ५८, १; १३८, २; ७. १०, १; ५९, २⁴; ८. ५, ३; ९. ४, १०; १०. ७, ३५; ११. ७, १; ८; १२. ३, ५; ६; १९. १५, ५; २०. ११, १; ४२, २; ६४, २; ७७, ५; ८०, १; १०७, २.
उभौ ३. २०, ६; ४. ३२, ७; ५. ७, ६; ६. ८९, ३; ७. ७३, ४; ८. ४, १३; ९. ३, ९; १०. ४, ८; ११. २, १४; ९, ३; १२, ११; १२. ४, १७; १३. २, ६; १३; १९. ३२, ५.
उम्भत ८. ८, ११.
उरः ९. ५, २०; १०. २, ४; ११. ११, १४; २०. १३७, १.
उरसा ११. ४, १०².
उरसि १०. ३, ११; ८, १८; १२. १०, २; १३. २, ३८; ३, १४; १९. ३२, २.
उराऽमथिः २०. ९७, २.
उरु २. १२, १²; ४. २, ४; ११, १; ५. ३, ६; ६. ४०, १; ४९, २; ७. ७, २; २७, ३²; १०. ७, ३५; ११. २, १०; २७; १२. १, २०; १४. २, ६९; १८. २, ४९; ३, ५९; १९. ९, १; २०. १३, २; ८७, ३.
उरुः ७. ३, १; ११. १, १९; २, ११; १२. ३, ३८; १३. ९, १.
उरुऽक्षयाः ७. ८२, ३.
उरुऽगाय २०. ७६, ४.
उरुऽगायः २. १२, १; ७. २७, १.
उरुऽगायम् ४. २१, ४; ५. १७, ११; १९. ११, ५.
उरुऽगूलायाः ५. १३, ८.
उरुऽग्राहैः ११. ११, १२.
उरुऽचक्षाः १९. १०, ८.
उरुऽज्मन् ६. ४, ३.
उरुऽज्रयः २०. ९२, १९.
उरुण्डाः ८. ६, १५.
उरुधाराऽइव २०. ७, ३.
उरुऽनसौ १८. २, १३.
उरुम् ६. ३३, ३; ७. ८९, २; ९. २, ११; १२. १, १; १४. १, ५८; १९. १५, ४; २०. १५, ६; २३, ५; ९५, १.
उरुऽयुगे २०. १००, ३.
उरुऽलोकम् ५. ३, ३.
उरुऽव्यचसम् १८. ३, ४९.
उरुऽव्यचसा ५. २७, ८.
उरुऽव्यचाः ५. ३, ८; २०. ८, २.
उरुऽव्यचै ६. ४१, २.
उरुषु ७. २७, ३.
उरुष्य ६. ४, ३.
उरुष्यतम् २०. १४३, ७.
उरुष्यताम् ६. ३, ३.
उरूची १९. १०, ३.
उरूची इति ३. ३, १.
उरूची इति ४. २६, २.
उरूचीम् ७. ६, २.
उरोः ७. २७, ८; १२३, १.

उरौ १८. २, २०; २०. १००, ३; १२९, १.
उर्वः १६. ३, ३.
उर्वरा १४. २, १४.
उर्वराः १०. १०, ८.
उर्वरायाम् १०. ६, ३३.
उर्वरीःऽइव १०. ४, २१.
उर्वशीः १८. ३, २३.
उर्वारुकम्ऽइव १४. १, १७.
उर्वार्वाःऽइव ६. १४, २.
उर्वि १९. ४७, २.
उर्विया ५. १२, ५; १८. १, २.
उर्वी ४. २, ४; १६. ३, ६.
उर्वी इति ४. २६, ३; ११. ७, ८; १८. १, ३२; २०. ३५, ८.
उर्वीः ३. २०, ९; ४. ११, १; ८. ९, १६; ९. २, ११; १०. ७, ३५; १३. १, ४; ४६; ३, १; ६; १८. २, ६; २०. ७१, ३.
उर्वीः ५. ३, ६.
उर्वीभिः १२. २, ४८.
उर्वीम् १८. ३, २२.
उर्व्यः ११. ९, १८.
उलपेषु ७. ६८, १.
उलम् १२. १, ४९.
उलुलयः ३. १९, ६.
उलूकः ६. २९, १.
उलूकऽयातुम् ८. ४, २२.
उलूखलम् ११. ३, ३; १२. ३, १३.
उलूखलऽमुसलानि ९. ६, १५.
उलूखले १०. ९, २६.
उल्का १९. ९, ८; ९.
उल्काः १९. ९, ९.
उल्काम्ऽइव २०. १६, ४.
उल्कुषीऽमान् ५. १७, ४.
उल्बः ४. २, ८.
उवक्थ १. १०, ३.
उवाच १०. १, ७.
उवाच २०. ८७, ३.
उवास ३. १०, १; १८. १, २०.
उवे २०. १२६, ७.
उशतः ७. १०२, ३; १८. १, ५६.
उशता २०. ९६, ३.
उशताम् १८. १, २०.
उशती ७. ४२, २; १४. २, ३८; १९. ४९, २; ४; ८.
उशतीः ७. ५१, १; १४. २, ५२; २०. १७, १.
उशतीःऽइव १. ५, २.
उशत्ऽभिः १८. ३, ४६.
उशधक् २०. ११, ३.
उशन् १८. १, ५६; ३, ४६; २०. ६७, ५; ८७, २.
उशना २०. २५, ५.
उशनाऽइव २०. ७७, २.
उशनाम् ४. २९, ६.
उशन्तः १४. २, ३८; १८. १, ५६[२].
उशन्तम् १८. १, २०.
उशन्ति १८. १, ३.
उशिक्ऽभिः २०. ११, ४.
उशिजः २०. ३३, ३; ७५, ३; ७७, ६.
उषः १६. ६, २; २०. १५, ३.
उषः १६. ६, ६[२].
उषः २०. १४२, २; ३.
उषत्ऽभिः २०. २६, ६; ४७, १२; ६९, ११.
उषसः ३. १६, ६; ७; ४. २१, १; ७. २३, २; ७७, ६; ८७, ४; १०. १, ३२; ७,

३१; ८, ३०; **१४.** २, ३१; ४३; ४४; **१६.** ४, ६; **१७.** १, ३०; **१८.** १, २७; ३, २४; **१९.** १०, १०; ४९, ६; **२०.** ७२, ३; ७६, २.
उ॒षस॑म् **१०.** २, १६; **१३.** २, ४६; **२०.** ३४, ७; ९१, ५; १०७, १५.
उ॒षसा॑ **८.** ९, १२; **१६.** ६, ५.
उ॒षसा॒नक्ता॑ **५.** १२, ६; २७, ८; **६.** ३, ३.
उ॒षसा॑म् **३.** ७, ७; **७.** ८६, २; ८७, ४; ५; **१४.** १, २४; **१८.** १, २७; २८; ४, ५८.
उ॒षसे॑ **१९.** ४८, २; ५०, ७.
उ॒षाः **४.** ४, २; **७.** ७२, १; **९.** १०, १; **११.** ८, ७; **१५.** २, १३; **१६.** ६, ५; **१८.** १, २०; **१९.** १२, १; ४८, २; ५०, ७.
उ॒षाम् **२०.** १६, ९.
उ॒षाम्ऽउ॑षाम् **१२.** २, ४५.
उ॒ष्णान् **८.** ९, १७.
उ॒ष्णिक् **१९.** २१, १.
उ॒ष्णिहा॑ **६.** १३४, १.
उ॒ष्णि॒हा॒ऽअ॒क्ष॒रः **१३.** १, १५.
उ॒ष्णिहा॑भ्यः **२.** ३३, २; **९.** १३, २१; **१०.** १०, २०; **२०.** ९६, १८.
उ॒ष्णीष॑म् **१५.** २, ५; १३; १९; २५.
उ॒ष्णेन॑ **६.** ६८, १.
उ॒ष्प॑लानि **१४.** १, ६०.
उ॒स्रा **१२.** ३, ३७.
उ॒स्राः **२०.** ९१, ४.
उ॒स्रियः॑ **१.** १२, १; **९.** ४, १.
उ॒स्रिया॑ः **४.** २६, ५; **१४.** १, ३२; **२०.** १६, ७; ७०, १; ८८, ५; ९१, ८.
उ॒स्रिया॑णाम् **२०.** १६, ६.
उ॒स्रिया॑भिः **३.** ८, १; **५.** २०, ३; २१, १.
उ॒स्रिया॑याः **७.** ७७, ५; ६; **८.** ३, १७.
उ॒स्रिया॑सु **७.** ७७, ४.
उ॒ह्य॒ते॒ **१४.** १, १३.
उ॒ह्यमा॑नम् **१४.** २, ९.

ऊ

ऊं॒ इति॑ **१.** ६, ४[२]; ११, १; १४, ३; २४, ४; **२.** २, ३; ३, ३; ४; ५; ९, २; १३, २; ३; २६, ३; ३०, २; **३.** ४, ६; ७, ५; ११, ४; २१, ४; २३, ५; **४.** ३, ४; ६; ४, २; १२, ३; १६, ९; ३०, ५; ३६, १०; ३९, ९; **५.** १, ५; ४, ६; ६, ४; ११, ११; १२, ४; १३, २; ३; १४, २; ६; २२, ९; **६.** १, २; ११, ३; २१, १; २६, २; ३; ५६, ३[२]; ५७, १; ७४, १; ८५, १; ८७, २; ९१, ३; १२४, २; ३; १३३, १[२]; १३६, २; **७.** ५, २; ६, २; २१, ६; ३२, १[२]; ५८, ८; ७३, २; ७७, ३; ७; ७८, ३; ८९, २; ९०, १; १०८, १; **८.** २, १३; ४, १३; २०; २१; ५, ५; ९; ६, ३; ९, १०; १६; १७; २३; २५; **९.** १, ६; ७; ४, ४; ७; ५, ७; ८, ९; १४, ६; १५; १९[२]; १५, ४; ६; **१०.** २, २; ३; ७; १३; ३, ५; ४, १८; ७, ३८; ८, ४; १६; २८; १०, १३; १४; १५; **११.** १, ११; ६, २०; १०, १; **१२.** १, १२; २, ३[२]; ३, ३; २६; ४७; **१३.** २, १६; २५; ४, ५[२]; ७, १३; **१४.** १, ४०[२]; **१५.** १०, ६; ७; **१६.** ९, २; **१८.** १, ७; १२; १४; १६[२]; ३७; ५०; २, ८; २६; ३०; ३३; ५०; ५१; ३, ६; ७; २०; ३८; ७१; ७३; ४, ११; ४४; **१९.** २, १[२]; ९, ९[२]; १०, २[२]; ३; ७[२]; ८; ९[२]; ११, १; २; २४, ४; ५; ६; ८; ३४, ६;

५३, ९; **२०.** ५, १; ८, ३; १०, १; १२, १; १४, १; ३; १८, १; २; २०, ४; २१, १; ३५, १; २; ३; ४; ५; ६; ७; ८; ११; १२; १३; १४; १५; ३६, २; ४५, १; ४७, १३; ५०, २[२]; ५७, ७; ५९, १; ६१, १; ४; ६२, १; ३; ८; ६४, ४; ६७, ७[२]; ७६, ४; ९०, २; ९२, ११; ९५, २; ९६, २; ५; ९; ९७, १; ३; १०४, १; ११८, १; १२६, ३; १३; १४२, १.

ऊचिम **७.** ८८, २; **१९.** ४४, ९.

ऊचुः **१८.** ४, ४९.

ऊतयः **२०.** ६०, ५; ७१, ५.

ऊतये **४.** १८, १; २५, ६; २७, १; **६.** ३५, १; ८०, २; **१९.** २४, ७; **२०.** ११, ११; १४, २; ३; १७, १; २०, १; २६, १; ४५, ३; ५७, १; ४; ६२, २; ३; ६८, १; ७०, १७; ७१, १५; ८५, ३; ४; १३७, २; १४३, ३.

ऊतिऽभिः **७.** ३२, १; **१७.** १, १०; **१९.** १५, १; **२०.** २१, १०; २५, १; २६, २; ३७, ३; ५४, २; ७०, १०; ८१, २; ९२, २१; ११८, १; १२४, ३.

ऊतिम् **२०.** २७, ६.

ऊती **७.** ८२, १; **१८.** १, ५१; **२०.** ३३, ३; ३४, १५; ३७, ११; १०५, ३; १२४, १.

ऊदिम **१०.** ५, २२.

ऊदुः **६.** २२, १; **९.** १५, २२.

ऊधः **४.** ११, ४; **८.** ११, ५; **९.** १२, १४; **१०.** ७, १९; ९, २२; १०, ७; **१२.** ४, १८.

ऊधनि **७.** ७६, १.

ऊधऽभिः **२०.** १४२, ४.

ऊनः **१०.** ८, ४४.

ऊनम् **१२.** १, ६१.

ऊनयीः **२०.** २१, ३.

ऊनेन **१०.** ८, १५.

ऊपे **२०.** १६, ३.

ऊबध्यम् **९.** ४, १६; १२, १७; **११.** ३, १२; **१२.** ९, १.

ऊमाः **५.** २, १; ३; **२०.** १०७, ४; ६.

ऊरुऽभ्याम् **२.** ३३, ५; **११.** ४, १३[२]; **२०.** ९६, २१.

ऊरुम् **१४.** २, ३९.

ऊरू इति **९.** १२, ९; १३, ७; **१०.** २, ३; ९, २१; **११.** ४, १३; १०, १४; **१४.** २, ३८; **१९.** ६, ५; **२०.** ९६, १४.

ऊर्जः **१२.** १, १२.

ऊर्जः **११.** १, १५; **१८.** ४, ५३; ५४; **१९.** ४५, ३; **२०.** ९४, ४; १०३, ३.

ऊर्जम् **२.** २९, ३; ५[३]; **३.** १०, ७; **४.** ३९, २; ४; ६; ८; **५.** १७, ११; **६.** २२, २; २८, १; ४०, २; ७९, २; **७.** ६२, १; ८४, ३[२]; **८.** ९, १३; **९.** १, ७; ९; २०; ५, २४; **१२.** १, २९; २, ४६; **१८.** ३, ४३; ४, ४; ३०; ३४; ३६; ४०; **१९.** ७, ४.

ऊर्जया **४.** २५, ४; **५.** १, ७; **९.** १०, २; **१०.** ६, २६.

ऊर्जस्वती **३.** १२, २; १७, ९; **९.** ३, १६.

ऊर्जस्वती इति **२.** २९, ५.

ऊर्जस्वन्तः **७.** ६२, २.

ऊर्जस्वान् **१९.** ४६, ६.

ऊर्जा **११.** ९, १३; **१६.** २, १.

ऊर्जाम् **२.** २९, ७; **८.** १४, ३; ४; **९.** ८, ३.

ऊर्जे ८. ११, ४; १४, १; १९. ३७, ३.
ऊर्जे १. ५, १; १८. ४, ८१.
ऊर्णऽम्रदाः १८. ३, ४९.
ऊर्णुवन्तु १. ११, २.
ऊर्णुष्व १८. २, ५८.
ऊर्णुहि ४. १४, ९; १८. २, ५०; ५१; ३, ५०; ४, ६६.
ऊर्णोति १५. १, ८.
ऊर्णोतु १. ११, ३; १८. ४, ५९.
ऊर्णोमि १८. २, ५२.
ऊर्ध्वः ४. १२, ६; ३५, ३; ७. १०७, १; ९. १४, १०; १०. २, २६; २८; ७, ४; ८, १९; १०, १९; ११. १, ७; ६, २५; ११, २१; १३. १, ११; १५. ३, १; १५, ३; १९. ४६, २; २०. ४५, ३.
ऊर्ध्वऽबुंध्नः १०. ८, ९.
ऊर्ध्वम् ५. २७, ९; १०. २, ३; २४; २५; ८, १४; ११. १, ९; १८. ३, २९.
ऊर्ध्वऽमायुः ५. २०, ४.
ऊर्ध्वया २०. ६७, ३.
ऊर्ध्वऽस्वप्नाः ६. ४४, १.
ऊर्ध्वा ३. २७, ६; ५. २७, १; ७. १९, २.
ऊर्ध्वाः ५. २७, १; १०. २, ११; १२. १, १३; १३. ३, १६.
ऊर्ध्वान् १३. १, ५३; ५४.
ऊर्ध्वाम् १५. ६, ४; १४, १७.
ऊर्ध्वायाः ४. ४०, ७; ५. १०, ६; ९. ३, ३०; १५. ४, १६; १८; ५, १२; १३; १९. १७, १०; १८, १०.
ऊर्ध्वायाम् ३. २६, ६; ४. १४, ८; १८. ३, ३५.
ऊर्ध्वायै १२. ३, ६०.
ऊर्मयः ६. ५२, २; २०. १६, १.
ऊर्मिः १०. ५, १६; १४. २, १६; २०. २८, ४; ३९, ५.
ऊर्वम् २०. ८८, २.
ऊर्वाः १९. ६०, २.
ऊवुरित्यूबुः २०. ३५, ८.
ऊषिम ७. ११४, ७.
ऊष्मार्णम् ६. १८, ३.
ऊह ११. १, ९; १८. २, ५७.
ऊहतुः ६. ८२, २.
ऊहतुः १९. ४४, १०.
ऊहसि २०. ११४, २.
ऊहामि १४. १, ३८; १९. ३७, ३.

ऋ

ऋक् ११. ९, ५; १४. २, ७१.
ऋक्ऽभिः १०. १, १२; १२. १, ३८; ४, ४९.
ऋक्ऽभ्यः १०. ५, ३०; १३. ७, १०.
ऋकता २०. ८८, ५.
ऋर्कऽभिः १८. १, ४७; २०. ५४, ३.
ऋक्षऽग्रीवम् ८. ६, २.
ऋक्षाकम् १८. २, ३१.
ऋक्षीकाम् १२. १, ४९.
ऋक्ऽसंशितः १०. ५, ३०.
ऋक्ऽसामाभ्याम् १०. १, ११.
ऋग्मियम् २०. ७१, १५.
ऋघायमाणः २०. ३५, १३.
ऋचः ९. ६, १; १०. ५, ३०; ७, १४; २०; १०, १४; ११. ८, १४; ९, २४; १०, २३; १२. ४, २७; २८; १३. ७, १०; १५. ३, ६; ६, ८; १९. ६, १३; ५४, ३.
ऋचः ९. १५, १८; १९.
ऋचम् ७. ५६, १; ५७, १.

ऋचा ६. २८, १; ९. ५, ५; १५, १८; ११. ३, १४.
ऋचाम् १०. ८, १०; १५. ६, ९.
ऋचीषमः २०. १०४, ३.
ऋचीषमाय २०. ३५, १.
ऋच्छति १२. ४, ५३.
ऋच्छतु २. १२, ५; ४. १९, ६; ५. १४, ११; ६. २६, ३; १०. १, ३.
ऋच्छन्तु ८. ३, १४; १९. १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
ऋच्छराः १०. ९, २३.
ऋच्छात् ५. १०, १; २; ३; ४; ५; ६; ७.
ऋजवः १४. १, ३४.
ऋजिश्वना २०. २१, ८.
ऋजीयः ५. १४, १२; ८. ४, १२.
ऋजीषा ९. ६, १६.
ऋजीषी २०. १२, ७; ७७, १; ५.
ऋजु २०. ९१, २.
ऋजुऽक्रतुः २०. ५६, ४.
ऋजुऽगः १. १२, १.
ऋजुऽरश्मिः ४. २९, ७.
ऋञ्जते २०. ७०, ५.
ऋणधत् १८. १, ६.
ऋणम् ६. ४६, ३; ११८, १; २; ३; ११९, १; २; १९. ५७, १.
ऋणम्ऽइव १९. ४५, १.
ऋणात् ६. ११८, २; १९. ४५, १.
ऋणोः २०. १२२, २; ३.
ऋण्वताम् १८. २, ९.
ऋतऽउद्येषु १७. १, ३१.
ऋतऽजाताः १८. २, १५.
ऋतऽजाते ५. १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११.

ऋतऽज्ञाः ४. २, ६; १८. १, ४४; १९. ११, ५; २०. ३२, ३.
ऋतऽप्रजाता १. ११, १.
ऋतऽप्रजाताम् २०. ९१, १.
ऋतम् २. १०, ८; ७. ७६, १; ८. ३, ११; ९. ५, २१; १५, २३; १०. ७, १; ११; २९; ३०; १०, ३३; ११. ३, १३; ९, १७; १२. १, १; १४. १, ३१; १५. ६, ५; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; १८. १, ४; ३, २१; २४; २०. १२, ४; ९१, २.
ऋतऽयन्त २०. ५०, २.
ऋतवः २. ६, १; ८. ८, २२; ९, १५; १८; १०. ६, १८; ७, ५; ११. ३, १७; ८, २२; १०, ५; १२. १, ३६; २, २५; १३. १, १८; १५. ६, १७; १७, ५; ८; १८. ४, २.
ऋतऽवरि ५. १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ६. ३०, ३.
ऋतऽवरि १०. १०, ९; १६.
ऋतवरी इत्यृतऽवरी ६. ६२, १.
ऋतऽवरीः ३. १३, ७.
ऋतऽवा २०. ९०, १.
ऋतऽवानम् ६. ३६, १.
ऋतऽवृधः ११. ८, १९; २०; १८. २, १५.
ऋतऽवृधौ ४. २९, १.
ऋतऽसाताः १८. २, १५.
ऋतऽस्थाः ४. १, ४.
ऋतऽस्पृशः २०. ८८, ३.
ऋतऽस्पृशम् २०. ४२, १.
ऋतस्य २. १, ४; ५; ४. ३५, १; ५. १२,

२; ११; १७, १; ६. २२, १; ३६, १; ११४, १; २; १२२, १; १३४, १; ७. ६, २; ८. ९, १३; १६; २१; ९. ३, २२; १४, १३; १५, १५; २२; ११. ४, १७; १२. १, ६१; १३. ३, ९; १९; १४. १, १९; १५. ६, ६; १७. १, १६; १८. १, ६; ३, ४०; ४, ३; २०. १६, ४; १७, ९; ६३, ९; ११५, १; ११९, १; १२६, १०; १३८, २[२]; १४३, ३.
ऋतानि ७. १, १; ५९, २.
ऋतिः १२. ७, १४.
ऋतिऽसहम् २०. ९, १; ४९, ४.
ऋतुः ७. ५१, २; ९. ५, ३१; ३२; ३३; ३४; ३५; ३६.
ऋतुऽथा ५. १२, १०; ९. १५, २६; १३. ३, २; १४. १, १६; २०. १२५, ३.
ऋतुना २०. २, १; २; ३; ४.
ऋतुऽपतीन् ३. १०, ९; ११. ८, १७.
ऋतुऽभिः १. ३५, ४; ३. ८, १; ५. २८, २; १३; ११. १, १६; ४, ६; ७, २०; ९, २०; १२. २, २५; ३, ३२; १७. १, २९; २०. ६७, ७.
ऋतुऽभ्यः ३. १०, १०; १९. ३७, ४.
ऋतुम् ८. ९, १७; ९. ५, ३१; ३२; ३३; ३४; ३५; ३६.
ऋतुऽशः ९. ५, १३.
ऋतून् ३. १०, ९; ६. ३६, २; ६१, २; ३; ७. ८६, १; ८. ९, १०; ११. ८, १७; १४. १, २३; १८. १, १८; १९. ५९, ३.
ऋतूनाम् १६. ८, २०.
ऋतूनाम् १५. ६, १८.
ऋते ४. २६, ६; ९. १४, ८; १२. ५, १; १४. २, ४७; २०. ३४, ९; १२६, १२.
ऋतेन ३. १२, ६; ६. ४७, ३; ११४, १; २; १०. ८, ३१; ११. १, २३; १४. १, १; १७. १, २९; १८. १, २९; ३०.
ऋतौ ११. ६, ४.
ऋत्वा ४. ४०, १; २; ३; ४; ५; ६; ७; ८; ६. १२०, २; १२. ४, ५३,
ऋत्विजः ८. ९, २१; ९. ७, ६; १०. ९, ४; १२. १, ३८; १९. ११, ५; ४२, २; ५८, ६.
ऋत्विजः ६. २, १.
ऋत्वियः ३. २०, १; २०. २३, २.
ऋत्वियम् ७. ७५, १.
ऋत्वियाय १२. ३, २९.
ऋत्विये इति १४. २, ३७,
ऋदन्तु ८. ४, २४.
ऋधक्ऽमन्त्रः ५. १, १.
ऋधेम १९. ५५, ४.
ऋध्यताम् ४. ३६, ४; ८. २, १३; १४. १, २१; १९. ५२, ५.
ऋध्यन्ते १२. ४, १९.
ऋध्याम् ७. ५२, ३.
ऋध्यासम् ६. ९४, ३.
ऋन्धन् ५. १२, २.
ऋभवः ६. १०८, ३; १९. ११, १; २०. ९९, १.
ऋभवः ९. १, १३.
ऋभुः ४. १२, ७; ६. ४८, २; १०. १, ८.
ऋभुऽभिः २०. १४१, २.
ऋभुम् १. २, ३.
ऋभूणाम् ९. १, १३.
ऋभ्वसम् २०. ९२, १८.
ऋभ्वाणम् ५. २, ७; २०. १०७, १०.
ऋशःऽइव ४. ४, ७; ६. १०१, ३.

ऋषति ९. ४, १७.
ऋषतु ४. ३७, ६; ८; ९.
ऋषन्तु ८. ७, ९.
ऋषभः ३. ६, ४; ४. ३८, ५; ५. २०, २; ९. ४, १; ३; ७; १०. १०, १०; १९. २७, १; ३६, ५.
ऋषभऽदायिने ९. ४, २०.
ऋषभम् ९. २, १; ४, ९; १४; १५; १८; १९.
ऋषभस्य ४. ४, ८; ६. ३८, ३; ७. ११८, २; ९. ४, ११; २३; १४. २, १४.
ऋषभाः ३. २३, ४.
ऋषभाणाम् ४. ४, ४.
ऋषभासः ४. २४, ४.
ऋषयः २. ६, १; ३५, २; ४; ४. २३, ५; ६. ४१, ३; १०८, ३; ४; १३३, ५; ८. ५, १०; ९, ७; १४; ९. १४, १६; १०. ७, १४; ८, ९; १०, २६; ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ११, २५; १२, १०; १२. १, ३९; २, २९; १७. १, १४; १८. ३, ६४; १९. ३३, ३; ३५, १; ४१, १; २०. ८८, १; ११९, ३.
ऋषयः ८. ९, ८.
ऋषिः ११. १०, १४; १८. ३, ४१; २०. ५०, २; १४०, २; ५.
ऋषिणा १३. १, ५५.
ऋषिणाऽइव ८. ५, ८.
ऋषिऽप्रशिष्टा ११. १, १५.
ऋषिऽभिः ६. १२, २; ७. ९४, २; ९. १, १५; १०. ५, ४७; १८. ३, ४७; ४८; २०. १०४, २.
ऋषिऽभ्यः १८. २, २; १९. २२, १४.
ऋषिम् ४. ३०, ३.
ऋषिऽस्तुताम् ६. १०८, २.
ऋषी इति ५. ३०, १०.
ऋषीणाम् ४. ३९, ९; ६. १३३, २; ४; ८. ९, २३; १०. १, १२; १६. २, ६; ८, १२.
ऋषीन् ८. ९, २४; ११. १, २६; ३५; १८. २, १५; १८.
ऋष्टिऽभिः ८. ३, ७; २०. ६७, ४.
ऋष्टीः ४. ३७, ८; ९.
ऋष्णवः १९. ३५, ५.
ऋष्व १८. १, ३४.
ऋष्वः ७. १२, १; २०. ४७, ३; १३७, १४.

ए

एकऽअक्षरम् ५. २८, ८.
एकऽअनूचेभ्यः १९. २३, २२.
एकऽअष्टका ३. १०, १२.
एकेऽअष्टके ३. १०, ५.
एकऽअष्टके ३. १०, ८.
एकऽऋचेभ्यः १९. २३, २०.
एकऽऋतुः ८. ९, २५; २६.
एकऽऋषिः ८. ९, २५; २६; १०. ७, १४.
एकेऽएकया ३. २८, १.
एकः २. १, ३; २, १; २; ३. १३, ४; ४. २, २; ७; १०, ६; १७, ८; ३१, ४; ३७, ११[२]; ६. ३६, ३; ७. २२, १; ८. ४, ३; ८, १२; ९, २६[२]; ९. १४, २; १०; १५, २६; १०. २, १४; ८, ५[२]; २८; ३६[२]; १०, २४[२]; १३. २, ३; २६; ३, १८; ४, १२[२]; ५, ७[२]; १८. ४, ११; २०. १२, ५; २७, १; ३५, १५; ३६, १; ३७, १; ६१, ६; ६२, १०; ६३, ४; ६५, १; ७०, १५; ८७, ६.

एकऽचक्रम् ९. १४, २; १०. ८, ७; १३. ३, १८.

एकऽज ४. ३१, ३.

एकऽजः १०. ८, ५[२].

एकऽजम् ६. ९९, १; ९. १४, १६.

एकऽतेजनाम् ६. ५७, १.

एकऽधा ५. १७, ८; ८. ९, २६; १०. १०, ५.

एकऽनेमि १०. ८, ७; ११. ६, २२.

एकऽपत्नीः १०. ८, ३९.

एकऽपदः १३. २, २७.

एकऽपदी ९. १५, २१; १३. १, ४२.

एकऽपात् १३. २, २७; ३, २५; १९. ११, ३.

एकऽपादः १३. १, ६.

एकम् १. १२, १; ५. ११, ६; १७, ५; २८, ६[३]; ७. २२, १; ८. ८, १२[३]; ९, ३[२]; १५; २६; ९. १४, ७; १५, २८; १०. ७, ९; २५; २६; ८, ४; ११; २५[२]; ११. २, २२; ६, २१; १२. ३, ३९; १३. १, ४५; ३, १७; १४. १, १४; १६; १५. १, ३; १७, १०; १८. २, ६; ३, ७[२]; ४, ६४; १९. ४५, ५[३]; २०. ७२, १.

एकऽमुखाः ९. ४, ९.

एकऽमूर्ध्नीः ८. ९, १५.

एकया ७. ४, १; १७. १, १७; २०. ९१, ४.

एकऽराट् ३. ४, १.

एकऽरात्रः ११. ९, १०.

एकऽरूपः १२. ३, २१.

एकऽरूपम् २. १, १.

एकऽरूपाः २. ३४, ४.

एकऽवाद्याम् २. १४, १.

एकऽविंशः ८. ९, २०.

एकऽवीरः १९. १३, २.

एकऽवृत् ८. ९, २५; २६; १३. ४, १२; ५, ७.

एकऽवृतः १३. ४, १३; ५, ८.

एकऽवृतम् १३. ५, २; ३; ४; ५; ६; ७; ८; ६, १; ३.

एकऽवृषः ४. २२, ६; ७; ५. १६, १; ६. ८६, १; २; ३.

एकऽवृषम् ४. २२, १; ५.

एकऽव्रात्यः १५. १, ६.

एकऽशतम् ३. ९, ६; ५. १८, १२; ७. १२०, ३; ८. २, २७; ११. ८, १६; १९. ४६, ५.

एकऽशफे ५. ३१, ३.

एकऽशीर्षाणः १३. ४, ६.

एकऽशुङ्गाः ८. ७, ४.

एकऽश्नुष्टीन् ३. ३०, ७.

एकस्मिन् १२. ३, ३६; १८. १, १७.

एकस्य ९. १५, २६; १८. १, ३.

एका ५. १५, १; ६. ८३, २[३]; ७. ४४, १; ८. ९, १३[३]; ९. ५, १०.

एकाः ७. ४४, १[२].

एकाकिना १९. ५६, १.

एकादश १९. २७, ११; १२; १३; ४७, ५.

एकादशऽऋचेभ्यः १९. २३, ८.

एकादशः ५. १६, ११.

एकाम् ५. १, ६; १५. १३, १.

एके ६. १२२, २[२], १०. ७, २७; ८, ३६; १०, ३२[२]; १८. २, १४; १९. ५६, २.

एके इति १०. ७, ४२.

एकेन ५. ११, ६; ११. १०, ३३[३]; १९. ४५, ५.

एकेनऽएकेन १०. ८, ३०.

एकेभ्यः १८. २, १४.

एकोनविंशतिः **१९**. २३, १६.

एजंत् **९**. १५, ८; १९; **१०**. ८, ६; **१२**. १, ३; ४; **१३**. २, ३१.

एजंति **७**. २१, ६; **८**. ९, ८; **१०**. ८, ११; **१२**. १, ४६; **१९**. ४७, २.

एजतु **४**. ४, २.

एजंत्ऽएजत् **४**. ५, ४.

एजत्ऽकाः **५**. २३, ७.

एजंथ **६**. २२, २.

एजथुः **१२**. १, १८.

एजांति **६**. २२, ३.

एणीऽइंव **५**. १४, ११.

एत **११**. १, १८.

एतत् **१**. ३५, २; **२**. १३, २; **३**. ११, १; २१, १; २; ३; ४; ५; ६; ७; २२, १; २९, ७; **४**. ७, ७; ११, ८; **५**. ३, ५; ६, २; १०, १; २; ३; ४; ५; ६; ७; १९, १०; **६**. २९, १; ३२, १; ११३, १; ११८, २; १२३, ५; **८**. १, १०; **९**. ५, ११; ७, १; ८, ९; १२, २५; १४, ४; **१०**. १, २८; ८, २४; **११**. १, ३१; ५, १; ७, २३; **१२**. ३, ८; ३०; ३७; ४८; ४, १४; १५; ४८; **१३**. २, १३; ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; **१४**. १, १४; २९^{२}; २, २१; ४१; ६९; **१५**. १७, ८; **१६**. १, ८; **१८**. १, २; ३; १२; १३; २, ३७^{२}; ५७^{२}; ३, ३९; ४०; ७३; ४, ३१; ६४; ७५; ७६; ७७; **१९**. २४, ४; ३३, ४; ५०, ६; **२०**. ९६, ६.

एतम् **१**. ३०, २; **२**. २९, ६; **३**. १२, ८; **४**. १, २; १४, ७; **६**. ८७, ३; १२२, १; ३; १२३, १; **८**. १, १०; **९**. ४, ८; २४; ५, १; ६; १२; ३७; ३८; **१०**. ६, ३५; ९, १; **११**. १, २९; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; **१२**. २, २३; ३, ७; १९; ३४; ३८; ४४; ४६; ५३; ५५; ५६; ५७; ५८; ५९; ६०; **१३**. ५, २; ३; ४; ५; ६; ७; ८; ६, १; ३; **१८**. १, ५५; ३, २; १३.

एतंवे **६**. २३, २; **२०**. ९२, १४.

एतंशम् **२०**. ३५, १५.

एतस्मात् **११**. ५, ३.

एतस्यं **७**. ४७, १; **९**. ७, ११; **१९**. ५२, ५.

एतस्याः **१९**. १७, २; ४; ६; ८; १८, २; ४; ६; ८.

एतस्याम् **५**. १७, ६.

एताः **४**. ११, ११; ३४, ५; ६; ७; **५**. २१, १२; २९, १४; **७**. १२०, ४; **९**. ५, १५; **११**. १, १५; **१८**. ४, ३३; **१९**. ६४, ४.

एतान् **१**. १९, ३; **५**. २२, ११; **६**. ११९, २; **१३**. १, ५३; **२०**. २१, ९.

एतानि **५**. २२, ८; **७**. ४३, २; ८४, ४; ८५, ३; **१९**. ८, १.

एताभिः **१२**. ४, ४९.

एताम् **२**. २९, ७; **५**. ११, २; १८, १; **७**. ४७, १; ७७, ७; **९**. ५, ४; १५, ४; **११**. १, २४; २, २६; **१२**. २, ४८; ३, २१; ४, २४; **१४**. १, ३१; **१७**. १, ८; **१८**. २, ५; ३, ४९; ५२; **१९**. ४, १; ४, ४; ५६, ४.

एतावंत् **४**. ११, ८; **२०**. ८२, १.

एतावंतः **५**. ११, ७.

एतावंती ४. ३०, ८.

एतासुं ५. १३, २.

एतिं ४. २४, १; ९. ४, ११; १३, ७; ११. २, २२; १२. ३, ४८; १९. ८, १.

एति १. १२, १; ४. १९, ६; ३४, ४; ५. १७, ९; १४; १८, १३; २३, ६; २७, ४; ६. २०, १; ५२, १; ८. ५, २; ९, ९[२]; २१; ९. ६, ४; १४, १४; १५, १६; २३; १०. २, १९; ८, १६; १०, ६; ११. ७, ६[२]; १२. २, ११; ४, २०; २१; १३. २, २५; २७; ४३; ३, २५; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १४. १, ७; १८. १, ५३; ४, १३; १५; ३७; ६०; १९. ५४, १; २०. १०७, १५.

एतुं ६. ७५, ३[३].

एतु १. ११, ४; १५, २; २१, १; २७, २; ४; २. ७, ५; १०, ५; ३४, १; २; ३. १, १; ४; ६; १५, १; १९, ६; २३, २; ५; ४. १, २; ३, २; ५; १५, ६[२]; ३८, ३; ५; ५. १२, ८; १३, ३; ४; १४, १३; २२, ४; ३०, ११; १३[३]; ६. २९, १; ३८, १; २; ३; ४; ५३, २[२]; ७६, १; ७९, २; ८९, २; १२१, ३; १४०, ३; ७. १०, २; ६९, १; ११३, १; १२१, २; ८. २, ८; ३, ११; १४; ४, १०; २१; ७, १५; ९. ४, ७; १०. १, १; २; १०; १९; ४, २२; २५; ११. १, १७; १२. १, ४०; ३, १७; १३. १, १०; १४. १, ३९; ५९; १८. ३, ६२[२]; ७२; ४, ५७; १९. ४, ४; १०, ८; १३, ९; ३९, १; ५२, ४.

एते २. ३६, ७; ५. १, ४; २, ३; ७. १०४, १; ८. ४, २०; ९. ७, ६; १३. ४, १३; १८. १, ९; ६१; २०. ३७, १०; ५६, ६; १०७, ६.

एते इतिं ७. ५६, १.

एतेनं ४. १५, ११; ५. ६, ५; ६; ७.

एतेभ्यः १८. २, ५४.

एतैः ११. १, ३६; १२. ३, २९.

एतो इतिं २०. ६५, १.

एतौ ७. ८६, १; ८. २, १८[२]; ९. ४, १२; ११. १, ९; १२. २, ३२; १३. १, ४६; २, ११; १४. १, २३.

एधः ७. ९४, ४; १२. ३, २.

एधतुः ११. ९, २२.

एधतुम् ९. २, ११.

एधन्ते १४. १, २६.

एधस्य २०. १२६, १८.

एधस्व १८. २, २५.

एधि ३. २८, ३; ४. ३१, २; ६; ५. ३०, ६; ६. ८७, २; १४२, २; ७. ८३, १; ११. १, ७; २२; १२. २, १०; ४९; १४. १, ४३; ४४[२]; २, १८; १८. ३, ७; ४, ३८[२]; १९. १३, ८; ५५, ३; ४.

एधिषीमहि १४. २, १७.

एधिषीय ७. ९४, ४.

एधिषीय ७. ९४, ४.

एनः २. ३५, ३; ५. ३, ४; ६. ९७, २; ११३, १; ११५, २; ११६, २; ३; ११९, ३; ७. ४३, १; २; १०. ३, ८; ५, २४; १२. २, ११; १६. १, ११; २०. ३४, १०.

एनत् ६. ११३, १; ११७, २[२]; ८. ९, ३; १०. ७, ४३[२]; १६. ६, ४; १९. २६, १.

एनम् १. ९, ३; १२, ३; ३०, २; ३५, २; २. ५, ७; ९, १[२]; २८, १; २; ३. ११,

१^{२}; २; ३^{२}; ४; **४.** ९, ५^{२}; ११, ४; १६, ७; **५.** २, १; १८, ५^{२}; ९; **६.** ५, १^{२}; ७५, १; ७६, १; ४; ११०, २^{२}; ११२, १; १२३, २; १३३, ३; **७.** १९, ४; १७, १^{३}; ३६, १; ५५, ४^{२}; ५८, ५; **८.** १, २^{३}; ३, ४^{२}; ८; ११; १४; ५, १३; **९.** १, २४; २, १३; १९; ३, १०; ४, १८; ५, ४^{२}; ५; २३; २४; १२, २६; **१०.** ३, १६; ५, ३६; ८, २३; **११.** १, १६; २४; ३०; ३, २८^{२}; २९^{२}; ४, १^{४}; २^{४}; ३^{४}; ४^{४}; ५^{४}; ६^{४}; ७^{४}; ८^{४}; ९^{४}; १०^{४}; ११^{४}; १२^{४}; १३^{४}; १४^{४}; १५^{४} १६^{४}; १७^{४}; १८^{४}; ५, ७; ७, २; **१२.** ३, ३४; ३६; ३८; ४२; ४३^{२}; ४, १९; ४८; ९, ७; ११, ११; १२; **१३.** ३, ११; **१५.** २, ८; १४; २०; २८; ४, ३; ६; ९; १२; १५; १८; ५, २^{२}; ५^{२}; ७^{२}; ९^{२}; ११^{२}; १३^{२}; १५^{२}; ७, ३^{२}; ५^{५}; १०, २; ८; १०; ११, २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२, २; १३, १२^{२}; १३; **१६.** ७, १^{६}; २; ३; ११; ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; **१८.** २, ४^{२}; ५; ८; १२; ५०; ५१; ३, ४; ५०; ७१; ४, ११^{२}; ६६; **१९.** १, ३; २४, २; ३; २६, १; ३६, २; ३८, १; ७२, १; **२०.** ३४, ५; ७१, ८; ९४, ३; ९५, १; ९६, ६^{२}; ७; ८^{२}; ९; ९७, १; १०७, ४; १४३, ८.

एनयोः **७.** ४५, १.

एनसः **२.** १०, ८; **५.** ३०, ४; **६.** ५१, ३; ८४, २; ११५, ३; **७.** ६६, २; ८२, ३; **१२.** २, १२; ४, ९; **१४.** २, ४४; ५९; ६०; ६१; ६२.

एनसा **२.** ३५, २.

एनस्यः **६.** ११५, २.

एनस्यमि **८.** ७, ३.

एना **४.** ८, ७; ३०, ८; **५.** ११, ५^{२}; ६^{२}; **९.** १४, ६; १७; १८; २२; १५, २५; **१२.** ३, ३३; **१३.** १, ४१; **१४.** १, २१; **१८.** १, ५०; ६०.

एनांसि **६.** ११५, १.

एनाः **५.** २९, १४; **६.** १४१, १; **७.** १२०, ४.

एनान् **२.** २५, ४; ५; **३.** ६, ५; ८^{२}; **४.** ३४, ३; ४; ४०, १; २; ३; ४; ५; ६; ७; ८; **५.** ३, १०; ८, ९^{२}; १२, ३; २१, १; **६.** १०४, ३; **७.** ८, १; **८.** ३, १६; ८, ३; ४; १०; ११; २१; **९.** २, ५; १०; १६; **१०.** ३, २; **११.** १, २०; २५; **१२.** ३, ३०; ४, १५; **१३.** १, २९; ३२.

एनाम् **३.** १२, ८; २५, ६; २८, २; **५.** ३१, १०; **७.** ७७, ७; **८.** ९, ९; **९.** १५, ४; **१०.** १, १; २; १०, ३२; **११.** १, ७; २१^{२}; २२^{२}; **१२.** ४, १; ११^{२}; १७; २२; २५; ५०; **१४.** २, ३७; **१८.** ३, ३; **१९.** ४, २.

एनीं **६.** ८३, २; **१८.** १, ३२.

एनीः **८.** ३, ७; **१८.** ४, ३३; ३४.

एने इति **५.** २, ९; **२०.** १०७, १२.

एनेन **९.** ९, २; ४; ६; ८; **१२.** २, ३७.

एनौ **७.** १००, २; **१४.** २, ६४.

एन्यः **२०.** ९२, ७.

एभिः **२०.** २१, ४^{२}.

एभिः **२०.** १३, ४.

एभ्यः **८.** ८, २४.

एभ्यः **२.** ३५, ४; **३.** २७, १; २; ३; ४;

५; ६; **६.** ९३, २; **१०.** ६, १६; ९, ७; **११.** १, २६; ३२; **२०.** ७५, ३; ८३, १.

एमि **४.** २८, ३; **५.** १, ७; **६.** ८, ३; ५१, २; **७.** ६२, १; **९.** ३, २२; **११.** ११, ४; **१९.** ४, २; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; **२०.** १२६, १९.

एरुम् **६.** २२, ३.

एत्सैमानः **६.** ११८, २.

एव **१.** १, २; ३^{३}; २, ४; ३, ६; ७; ८; ९; ११, ६; १३, ३; १५, २; ३१, ४; **२.** १, ३; २, १; २; ४, १; ९, ५^{२}; १०, २; ३; ४; ५; ६; ७; ८; १५, १; २; ३; ४; ५; ६; २८, १; ३०, १; ३६, ४; **३.** ६, ३; ६; ८, ३; १०, ४; ११, २; ६; १२, १; २; १४, ४^{२}; ५^{२}; १६, ५; १८, ३; २४, ४; २५, ६; ३१, ९; **४.** २३, २; ३०, ३; ८; ३२, २; ३९, १; ३; ५; ७; **५.** २, ९^{२}; ६, ३; ८, ३; ९; १७, ३; ८; ९; १८, ४; ११; १९, ११; २१, ४; ५; ६; २५, २; ३०, १; **६.** ८, १; २; ३; १७, १; २; ३; ४; १८, २; २९, ३; ४६, ३; ५८, २; ७०, १; २; ३; ७१, १; ७२, १; ७३, ३; ७४, ३; ८५, ३; ८७, २; ८९, २; ९७, १; १०२, १; १०५, १; २; ३; ११७, २; १२२, २; १२४, २; ३; १३८, ५; १३९, ४; ५; १४१, ३; **७.** १४, १; २८, १; ५२, १; ५; ६२, ७; ६९, १; ८३, १; ८७, ३; ९३, १; ११५, २; **८.** १, १८; २, ७; ९, ११; १०, १; ११, २; ७; ९; १३, ३; ७; १४, ३; ७; ११; १५; १५, ३; ४; **९.** १, ११; १२; १३; १६; १७; २४; २, ७; ८; ५, २२; २४; ३१; ३२^{२}; ३३^{२}; ३४^{२}; ३५^{२}; ३६^{२}; ६, ५^{२}; ६^{२}; ७; ८; ९; १०; ११; १२; १३; १४; १५; १७; ७, २; ८, ९; ११, १; २; ३; ५; ६; १४, ११; **१०.** १, १३; २०; ३२; ३, १३; १४; १५; १७; १८; १९; २०; २१; २२; २३; २४; २५; ६, ३३; ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १८; १९; २०; २२; ३९; ८, ११; १६; १७; २४; ३०; ४४; १०, २६; **११.** १, २०; ३, ११; ३०; ३१; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ६, १९; २१; १०, २; ६; **१२.** २, १०; १८; २५; ३९; ४९; ३, २०; २६; ४९; ४, १; १५; १६; १८; ३४; ११, ४; **१३.** १, १७; १८; १९; ४, ५; १२; ५, ७; ६, ४; **१४.** १, २२; ४३; **१५.** १, १; ६; ८; ३, ११; १०, ४; ५; ६; ११, ३; ४; ५; ६; ८; १०; १३, २; ४; ६; ८; १०^{२}; १४; १७, ९; १०; **१६.** ७, ४; **१७.** १, २०; २१; **१८.** १, १५; २, १४; १६; १७; ५९; ४, ३८; ५५; **१९.** २, ५; ६, ४; ७, ४; ९, २; ३^{२}; ४^{२}; ५^{२}; १४; ३१, ९; ३४, ४; ५०, ४; ५३, ४^{२}, ५७, १; **२०.** ८, १; १२, ६; ३४, १; ३५, ९; १०; १६; ६०, १^{३}; २; ४; ५; ६; ६४, ४; ६६, २; ७१, ४; ५; ६; ८८, ६; ९४, ४; ६; ७^{२}; ९६, ७; १०७, १२^{२}; १३९, ३; १४०, ४; ५.

एवम् **८.** १०, ३; ५; ७; ९; ११; १३; ११, १०; १२, २; ४; ६; ८; १३, ४; ८; १२; १६; १४, ४; ८; १२; १६; १५, १; ४; **९.** १, २३; २४; ७, ७; ९, १; ३; ५; ७; ९; १०; १०, ३; ५; ७; १०; ११, १४;

१२, २६; **१०.** १०, २७; ३२; **११.** ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ५, २; ५; **१२.** ४, २२; २३; ९, ८; १२, ८; **१३.** ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; **१५.** २, ३; ८; ११; १४; १७; २०; २३; २८; ३, ११; ४, ३; ६; ९; १२; १५; १८; ५, ३; १६; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ७, ३; ५; ८, ३; ९, ३; १०, १; ११, १; ७; ९; ११; १२, १; ४; ७; ११; १३, १; ३; ५; ७; ९; १४; १४, २; ४; ६; ८; १०; १२; १४; १६; १८; २०; २२; २४.

एवैः **८.** ४, ७; ९; **२०.** ९१, ११.

एवो इति **६.** ८४, ३.

एषः **२.** १, ४^{२}; २९, ४; ३५, ३; ३६, ४; **४.** १, ६; ११, ८; ३४, ५; **६.** ८४, २; १४०, २; **७.** ५७, १; १०२, ६; **८.** १, १०; **९.** ४, ५; ५, ९; २१; ३१; ३२; ३३; ३४; ३५; ३६; ७, ८; ९; १०; १२; ८, १; २; ३; ४; ५; ६; ७; **१०.** ८, २४; ९, २; **११.** ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; **१२.** २, २१; ३, ४५; **१३.** ४, ८; १२; ५, ७; **१४.** २, २४^{२}; ६८; **१६.** १, ८; **१८.** २, ३७^{२}; ३, ७०; **१९.** ५३, २; **२०.** २४, ८; ३४, ५; ६७, ६; ९०, ३; ९६, ४; १२६, २१.

एषंतु **६.** ६७, ३.

एषतु **६.** ६७, ३.

एषा **१.** १४, २; ३; **२.** २९, ७; **३.** २८, १; २; **५.** ११, १०; १७, ३; ४; १८, ३; **१०.** ८, ३०^{२}; ९, २; **११.** १, २३; २८; **१२.** ३, २२; ५१; ४, १०; ३९; ४२; ७, १; **१३.** १, २७; **१४.** १, २५; **१८.** १, २६; ५०; ३, ४९; **१९.** ५५, २.

एषाम् **१.** २९, ६; **३.** १९, २; ५^{४}; **६.** ८४, १; ११२, १; २; **७.** १३, ३; **१२.** २, २५; **१४.** १, २; **१९.** २८, ४.

एषाम् **१.** ७, ७; ८, ४^{२}; ९, ४; **२.** २६, २; ३२, ४; ३५, ४; **३.** १, २; ४; २, ४^{३}; ६; १९, ८; **४.** १६, १; ३३, ३; ३४, २^{२}; ३६, ४; **५.** ३, २; २३, ११; **६.** ४७, २; ६४, २; ६६, १; ३^{२}; १०४, १; **७.** ११३, १; **८.** ३, ६; ४, ३; ८, ६; २०^{२}; **९.** १५, २६; **१०.** १, १७; ८, ५; ८; २८^{३}; ३६^{२}; **११.** ८, ९; ११, १३^{२}; २३; १२, १६^{२}; २१; **१२.** २, २३; ४६; ३, १६; **१४.** २, २७; **१५.** १७, १०; **१८.** १, ६; ३, ६२; **१९.** १३, ९; ३१, ४; ४५, ५; ५३, ४; **२०.** १७, ४; ३५, १५; ९२, १५; १२५, २.

एषिं **१३.** २, ५.

एषि **४.** १९, २; ३; **६.** ९८, ३; **७.** ८६, २; **१२.** २, ४९; **१३.** २, १२; २०; २२; **१४.** १, २४; **१७.** १, १५; १६; १७; **१८.** १, ३९; **१९.** ३३, ३; **२०.** ७, १; २१, ७; ४७, १७; १९; १२६, २१.

एषु **१४.** २, ९; **२०.** २३, ४; ७१, ९.

एषु **६.** ३५, ३; ६७, ३; **१०.** ३, २५; **२०.** ३५, १६.

एष्यः **१२.** २, ३९.

एष्याः **१२**. ४, १६.
एष्यामि **७**. ६२, ७.
एह्राः **१२**. ३, ३३.

ऐ

ऐः **१०**. १०, १०.
ऐः **५**. २२, ११.
ऐक्षत **१३**. ३, ६.
ऐच्छत् **११**. ७, १५.
ऐच्छाम **८**. ५, ११.
ऐत् **१०**. ८, ३९.
ऐत् **१५**. १, ५; **१९**. ५३, ४.
ऐतम् **१८**. ३, ३८.
ऐताम् **८**. ९, १; **१४**. १, ११.
ऐनोः **२०**. ७७, ७.
ऐन्द्ध **१०**. २, १६.
ऐन्द्रः **५**. २०, २; **९**. ४, २२.
ऐन्द्राः **५**. ८, २.
ऐन्द्राग्नम् **८**. ५, १९; **११**. ९, ६.
ऐरत **२०**. १२, १.
ऐरयः **७**. ५७, २.
ऐरयत् **८**. ५, १४; **१०**. २, २६; **१५**. १, १; **१९**. ५४, ४; **२०**. ३८, ६; ४७, ६; ७०, ९.
ऐरयत **७**. ३, १.
ऐरयन् **१**. ११, २; **३**. ३१, ७; **४**. २, ८; **७**. २३, २.
ऐरयन्त **२**. १, ५; **६**. ४७, ३.
ऐरयेथाम् **७**. ४५, १.
ऐराऽवतः **८**. १४, १५.
ऐलबः **६**. १६, ३.
ऐलबऽकारेभ्यः **११**. २, ३०.
ऐलबम् **१२**. १०, १; २; ३.
ऐलयीत् **६**. १६, ३.

ओ

ओ इति **७**. ७५, २; **१८**. १, १.
ओकः **५**. २२, ५[२]; **१८**. ३, ८; **२०**. ५२, २; ५७, १५.
ओकसः **३**. २, २; **६**. ७५, १; **२०**. २६, ३; ९२, १५.
ओक्यम् **२०**. ९४, ९.
ओक्ये **२०**. २४, ८.
ओजः **१**. १२, १; ३५, २; ३; **२**. १७, १[२]; **३**. ५, १; १९, २; **४**. २४, ५; ३१, २; ३२, १; ४; **६**. १२५, २; ३; १२६, २; **७**. ५७, १; ८९, २; ९५, १; **९**. १, १७; ४, ८; **१०**. ३, १२; ५, १; २; ३; ४; ५; ६; **११**. ९, १८; १०, २०; **१२**. ६, १; **१८**. ४, ५३; **१९**. ३३, ४; ३४, ५; ३७, १; २; ४१, १; ४२, ४; ५२, २; ६०, २; **२०**. ६७, ६; ९४, ४; १०७, २; १०८, १; १३७, ११.
ओजसः **१९**. ४५, ३; **२०**. ९३, ५.
ओजसा **३**. १, ६; २, ६; **६**. ९७, ३; **७**. २६, १; **८**. ८, १२; १३; **१०**. ३, १३; ६, १; **११**. १२, १३; **१९**. १३, ६; ३३, ३; ३४, ५; **२०**. ५, ३; २१, ७; ३१, ५; ४२, ३; ५३, १; २; ५४, २; ५७, ११; १२; ५८, १; ७०, १४; ७१, ७; ९३, ६; ७; ८; १३७, ५; १३८, १.
ओजसे **८**. ५, २०; **१०**. ६, ६; ७[२]; ८; ९; १०; **११**. १२, ११; **१९**. २६, ३; ३७, ३; ४५, ६; ७; ८; ९; १०; ४६, १; **२०**. १५, ५; ११३, २.
ओजस्वान् **८**. ५, ४; १६.
ओजांसि **६**. ७, ३.
ओजायमानम् **२०**. ३४, ११.

ओजिष्ठः २०. ४७, २; १३७, १३.
ओजिष्ठम् २०. ५४, १; ८०, १.
ओजीयः ५. २, ४; ७. ५, ४; २०. १०७, ७.
ओजीयसः १०. ३, ७.
ओज्मानम् ४. १९, ८; ६. १२५, २; १९. ३४, ९.
ओणिम् २०. ३५, १४.
ओण्योः ७. १५, १.
ओतवः १४. २, ५१.
ओतवै ९. १४, ६.
ओते इत्याऽउते ५. २३, १; ६. ९४, ३.
ओदन ११. १, ३३.
ओदनः १०. १०, २५; ११. ३, ३०; ३१; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ५, १; १२. ३, ५.
ओदनम् ४. १४, ७; ३४, ३; ४; ८; ३५, १; ११. १, २३; ३, २६; २७; ३०; ३१; १२. ३, ४; १२; २७; १८. २, ३०; ४, ४२; २०. ९२, ११.
ओदनस्य ४. ३४, १; ११. १, १७; २४; ३, १; ११; २२; २३; १२. ३, ५१.
ओदनाः ११. ३, २७.
ओदनात् ११. ५, ३.
ओदनान् ९. ५, ३७.
ओदनानाम् ९. ५, १९.
ओदनाय १२. ३, ३२.
ओदनेन ४. ३५, १; २; ३; ४; ५; ६; ११. ३, १९.
ओपशः १४. १, ८.
ओपशम् ९. ३, ८; २०. २७, ५.
ओपशिनम् ६. १३८, १; २.
ओषं १९. २९, ७.
ओष ८. ३, २१.
ओषतम् ८. ४, १.
ओषतु १२. ११, ११; १२.
ओषधयः २. ३, ६; ३. २३, ६; २४, १; ४. १५, २; १६; ६. ९६, १; ८. १, १७; २, १५; ७, ३; ९; १६; ९. १२, १५; ११. ६, ६; १६; १७; ७, १४; २०; ९, २१; १२. १, २३; १४. २, ७; १५. ६, २; १८. १, १७; ३, ५६; १९. ९, १४; ३४, ७; ४४, ६.
ओषधिः ४. ४, ३; ६. ५९, २; ७. ३९, ५; १९. ३२, १.
ओषधिऽजाः १०. ४, २३.
ओषधिम् ३. १८, १; ४. ४, १; १४. १, ३.
ओषधीः ३. १७, ५; २१, १; २६, ५; ४. १७, २; २३, ६; ६. २२, २; २३, ३; ७. ९२, १; ८. २, २२; ७, १; ४; १०; १३; १७; १९; २४; २५; ८, १४; ९, २३; ११, ७; ९; ९. ४, १३; १०. १, ११; ५, ३२; ११. ६, ३; ४; ८, १; ११, २४; १२. १, २; ३, ३१; ५०; १३. १, २; ७, १५; १५. १४, ११; १९. ९, १; १०, ५; २०. ११, १०; १४३, ८.
ओषधीः ८. ७, ५; २१.
ओषधीनाम् ३. ५, १; २१, १०; ४. ४, ४; १५, १०; १७, ८; १९, ३; २२, ४; २७, ३; ३७, ६; ५. २५, ७; ६. १५, १; ३; ९५, ३; ७. ४०, १; ८. ३, १६; ५, ११; ७, २५; ९. ४, ५; १०. ४, २१; १२. १, १७; ५७; १४. २, ७०; १५. ६, ३; १९. ३१, ५; ३२, १०; ३९, ४.

ओषधीभिः २. १०, २; ४. १९, २; १२. ३, २८; १५. १४, १२; १९. १९, ९; २७, २.
ओषधीभ्यः ६. २०, २; १०. ९, ३२; १२. ३, ५९; १९. ३, १.
ओषधीम् ८. २, ६; ७, ६.
ओषधीऽमतीः १९. १७, ६; १८, ६.
ओषधीषु १. ३०, ३; २. ३१, ५; ४. २७, २; ६. ५८, २; १०. ४, २२; १२. १, १९; १८. २, ७; १९. ३, २; २०. १३९, ५.
ओषधीऽसंशितः १०. ५, ३२.
ओषधे १. २३, १; ३; २४, ३; २. २७, १; २; ३; ४; ५; ६; ३०, ४; ३६, ८; ४. ६, ८; ७, ६; १२, ५; १७, १; १९, २; ४; २०, २; ६; ३७, १; १०; ५. १४, १; २; १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ६. १२७, १; १३६, १; १३७, ३; १३८, १; ८. ६, ९; १०; १९. ३२, ३; ३४, ९.
ओषध्या ४. १८, ५; १०. १, ४.
ओषन्ती १२. १०, ८.
ओषम् २. ३६, १; ७. ७७, ६; १२. ३, ३१.
ओष्ठौ १०. ९, १४.
ओहते २०. ५०, २; ९२, ११.
ओहम् २०. ३५, १.
ओहसे २०. ४५, १.

औ

औक्षः २. ३६, ७.
औक्षऽगन्धिः ४. ३७, ३.
औक्षन् १९. ६, ११.
औदुम्बरः १९. ३१, २; ६; ७; १०; ११; १३; १४.
औदुम्बरम् १९. ३१, ४.
औदुम्बरस्य १९. ३१, ३.
औदुम्बरेण १९. ३१, १.
और्णात् १३. ३, २२.
और्णोत् ७. १, २; १०. २, १८.
औहत् १०. २, १७.
औहत ९. १५, ७.
औहताम् ७. ५५, १.
औहन् ५. २८, ८; १२. २, २९.

क

कंसाः १०. १०, ५.
कः ३. १९, ८; २९, ७; ४. ५, २; २५, २; २८, ५; ५. १९, १०; ६. २८, २; ७. ८, १; ७३, ३; ८०, ३; १०८, १[४]; १०९, १; ८. ८, १९; ९, १०[५]; २५[२]; ९. १, ६[२]; ११, ४; १४, ४[२]; १८; १९, २३; १०. २, १; २; ३; ४; ५[२]; ६; ७; ११; १२[५]; १३[३]; १४[३]; १५[४]; १७[४]; ४, १८; ७, २३; ८, ४; ११. ६, २५; १०, १; १२; १४; १६; ११, २०; १२, १९; १२. १, १८; २३; २४; २५; ४, ७; १४. १, ५६; १८. १, ६; ७[३]; ३३; ४८; १९. २२, २१; २३, ३०; २०. ३६, ४; ५०, २; ५३, १; ५७, ११; ७६, ३; ९३, २; १२४, २; १४३, ३.
कः ७. ११, १; १८. १, ५; १९. ३२, ९.
ककजाऽकृता ११. १२, २५.
ककाटिकाम् १०. २, ८.
ककुत् ६. ८६, ३; ९. ४, ८; १२, ५; १०. ९, १९.
ककुत्सलम्ऽइव १८. ४, ६६.
ककुदात् १०. १०, १९.
ककुदि ३. ४, २; ७. ८०, ३.

ककुप् १३. १, १५.
ककुभाः ८. ६. १०.
ककुहासः २०. १४३, २.
कक्षीवन्तम् ४. २९, ५.
कक्षीवान् १८. ३, १५; २०. १४०, ५.
कक्षे ६. १२७, २.
कक्ष्या∫ ८. ४, ६.
कक्ष्या∫ऽइव १८. १, १५.
कङ्कऽपर्वणः ७. ५८, १.
कङ्कूषेभ्यः ९. १३, २.
कटुकम् १४. १, २९.
कर्णः १०. ९, २६.
कर्णाः ११. ३, ५.
कण्टकः १४. २, ६८.
कण्वः ४. ३७, १; ७. १६, १; १८. ३, १५.
कण्वऽजम्भनी २. २५, १.
कण्वम् २. २५, ३; ४. २९, ५.
कण्वऽवत् २. ३२, ३; ५. २३, १०; २०. ११५, २.
कण्वस्य ६. ५२, ३.
कण्वाः २०. १८, १; १३८, ३.
कण्वाःऽइव २०. १०, २; ५९, २.
कण्वान् २. २५, ४; ५.
कण्वासः २०. १२०, २.
कण्वेन ४. १९, २.
कण्वेभिः २०. ५२, ३; ५७, १६.
कण्वेषु २०. १४१, ४.
कत् १८. १, ४; ७; ३३; २०. १४, १; ५०, १; २[२]; ५३, १; ५७, ११; ६२, १; ७६, ३; ४[२]; ९७, ३; ११२, १.
कतमः ८. ८, ६; ९, १; २५; १०. २, ८; ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १८; १९; २०; २२; ३९; ८, १३; ११. ६, २२.
कतमत् ५. ३, ४; ९. २, १०.
कतमस्याः ८. ९, १.
कतमा १०. ८, १०; १२. ४, ४५.
कतमे १०. २, ४; ८, ३५.
कतरः ७. ४५, १.
कतरेण ८. ९, १.
कति १०. २, ४[४]; १२. ४, ४३; २०. १२६, २०.
कतिऽधा ८. ९, १०[२]; १९. ६, ५.
कथम् ५. ११, १[२]; ७. ८१, १; ८. ९, १९[२]; २०[४]; १०. ७, ३७[२].
कथा ८. १, १६.
कदा १. २०, ४; ४. ३४, ३; ६. १३०, ३; ७. १०, ३; ८. ४, ७; १०. ७, ३७; ११. ६, २१; २०. ५०, २; ५२, २; ५७, १५; ६३, ५[२].
कद्रीची ९. १४, १७; १३. १, ४१.
कनक्नकम् १०. ४, २२.
कनिक्रदत् २. ३०, ५; २०. ८८, ५.
कनिष्ठः १०. ८, २८.
कनिष्ठिका १. १७, २.
कनीनः २०. ९२, ११.
कनीनिका ४. २०, ३.
कनीयः ३. १५, ५; १२. ४, ६.
कन्यला ५. ५, ३.
कन्यलाः १४. २, ५२.
कन्या∫ १. १४, २; १०. ४, २४; ११. ७, १८; १४. २, २२.
कन्या∫ऽइव ६. २२, ३.
कन्या∫नाम् २. ३०, ४.
कन्या∫याम् १०. ३, २०; १२. १, २५.

कपालम् १०. २, ८.
कपालानि ९. १३, २२.
कपिः ६. ४९, १; २०. १२६, ५.
कपिःऽईव ३. ९, ४; ४. ३७, ११.
कपृत् २०. १२६, १६; १७; १३७, २.
कपृथम् २०. १३७, २.
कपोतऽउलूकाभ्याम् ६. २९, २.
कपोतः ६. २७, १; २; ३; २९, १.
कपोतःऽइव २०. ४५, १.
कपोतम् ६. २८, १.
कफोडौ १०. २, ४.
कबन्धम् ९. ४, ३; १०. २, ३.
कब्रु ११. ३, ६.
कम् २. १, ५; ३. ११, १; ४. ९, १; ५. ११, २; ६. २०, १; ६१, १; ८४, १; ११०, १; ८. २, २५; ९. ३, ६; १४, १७; १०. ६, ७; ११. १०, ५; ११; १३. १, ४१; १४. १, ४२; ५३; २, ३०; १५. १०, ३; १८. ३, ४१; १९. ४६, १; २०. ५६, ३[२]; ९६, ६; १२६, २२.
कम् १. १७, ४; ३. १२, ३; ७. २७, १; २०. ६३, १; ९७, ३; १२४, ४.
कमलम् ८. ६, ९.
कम्बले १४. २, ६६; ६७.
कम्बूकान् ११. १, २९.
कया २०. ७६, ४; १२४, १[२].
कर १९. ५७, ३.
करः २०. ३६, १०.
करः ४. २०, ७; ५. १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २०. २३, ६.
करञ्जम् २०. २१, ८.
करणः ६. ४६, २; १६. ५, १; ४; ५; ६; ७; ८.

करत् ४. २२, ५; ६. ५९, २; ७. ९९, १.
करत् २. ९, ५; ४. ८, ६; ५. ४, १०; ६. १०३, १; ७. ३१, १; १९. ३१, १; ३४, २; १०; ३५, ५; ४५, ३; ४६, ७; २०. २०, ७; ५७, १०; १३७, ३.
कराति १९. १५, ५.
करते २०. ७७, १; १४३, ३.
करन् ६. २४, २.
करम् १. ३, १; २; ३; ४; ५; १४. १, १८.
करम्भम् ४. ७, ३; ६. १६, १.
करम्भेण ४. ७, २.
करवः १३. १, ५६; ५७.
करवात् १०. २, ५.
करसि १८. २, ४.
करसे २०. ७६, ४.
कराम १८. १, ५२.
करामहे ७. ७, २.
करिक्रत् २०. ७२, २; ७५, १.
करिक्रतम् १०. ४, १३.
करिक्रति ४. १८, ३.
करिरिति कः २०. ३५, ११.
करिष्यति ९. १५, १८; १०. ६, २.
करिष्यथ ५. १३, ७.
करिष्यन् २०. ३७, ८.
करिष्यामि ५. ८, २.
करीषिणीः ३. १४, ३.
करीषिणीम् १९. ३१, ३.
करुणे १२. ३, ४७.
करुमाः ८. ६, १०.
करूकरम् ११. ११, ८.
करेण १२. २, २.
करेणऽइव २०. ९१, ६.

करोति १२. ९, ७.
कर्कर्यः ४. ३७, ९.
कर्की ४. ३८, ६.
कर्कीम् ४. ३८, ६; ७.
कर्णाः १५. १८, ३[२].
कर्णतः ९. १३, ३.
कर्णयोः ६. १४१, २; १९. ६०, १.
कर्णऽशूलम् ९. १३, १; २.
कर्णा ५. १३, ९.
कर्णाभ्याम् २. ३३, १; ९. ४, १७; १३, २; २०. ९६, १७.
कर्णिनी १०. १, २.
कर्णे २०. ९४, ३; १२६, ४.
कर्णौ १०. २, ६; ९, १३; १२. ४, ६; ७, ११; १६. २, ४[२].
कर्ण्यैः ६. १२७, ३.
कर्तम् ११. २, २.
कर्तम् ४. १२, ७.
कर्तम् ३. १७, ९.
कर्तवे १३. २. १२; २०. ९९, १.
कर्ता २. १२, ९; ५. २९, १.
कर्तारम् २०. ४६, १.
कर्तारम् ४. १९, ६; ५. १४, ११; १०. १, ३; २९.
कर्तुम् ४. १८, ६; ५. ३१, ११.
कर्तृन् १०. १, १४; १७.
कर्तोः २०. १२३, १.
कर्त्रीम् १०. १, १९; ३२.
कर्त्रे १०. १, ३०.
कर्त्वम् १. ४, ३.
कर्त्स्यामि १०. १, २१.
कर्म ६. २३, ३; ११. ९, १७; १०, २; ६; २०. ११, ६; ९५, १.
कर्म ४. ३९, ९.
कर्मऽकृत् २. २७, ६.
कर्मऽकृत्याय ४. २४, ६.
कर्मणः ११. १०, ६.
कर्मणा १०. ९, १९; १६; १७; १८; १९; २०; २१; २०. ५९, ४; ९२, १८.
कर्मणि ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
कर्मणे १९. ३७, २.
कर्मण्याः ६. २३, २.
कर्मन् १२. ३, ४७; २०. १४, २; ६२, २.
कर्मन्ऽकर्मन् ४. २३, ३.
कर्मऽसु २०. १२५, ४.
कर्माणि ४. ७, ७; ५. ६, २; ७. २७, ६; ९६, १; १०. २, १८; १९. ६८, १; २०. ३५, १३.
कर्माराः ३. ५, ६.
कर्वरम् १०. ४, १९.
कर्वराणि ५. २, ६; ७. ३, १; २०. १०७, ९.
कर्शफस्य ३. ९, १.
कर्षे १३. २, ३.
कर्षेत् १५. १३, १२[२].
कलशः ९. १, ६; ४, १५; २०. ८, ३.
कलशम् ९. ४, ६; १८. ४, ३०.
कलशान् १८. ४, ५८.
कलशे ७. ८१, २; १८. ४, ६०.
कलशैः ३. १२, ७.
कलाः १९. ५७, २.
कलाम् ६. ४६, ३; १९. ५७, १.
कलिऽभिः १०. १०, १३.
कलिम् ७. ११४, १.
कल्पत् ११. ७, २६.

कल्पताम् ५. ७, ३.
कल्पते ४. ७, २; ५. १९, १५; ८. ९, २०; १०. ९, ४.
कल्पम् ८. ९, १०.
कल्पमानः ३. ८, १; १३. २, ३३; ४३; १८. ४, १३.
कल्पय १. २४, ४; ४. १२, ५[२]; ९. ५, ४; ११. १, ३६; १२. २, २५.
कल्पयताम् ६. ८८, ३.
कल्पयति १२. ४, ३१.
कल्पयतु ५. २५, ५.
कल्पयन्तः ८. ९, १४; ९. १५, १९.
कल्पयन्ताम् ७. ६९, १.
कल्पयन्ति ९. ६, ७; १०. १, १.
कल्पयन्ति ९. ६, ७; १८. ४, २.
कल्पयन्तु ९. ५, १३.
कल्पयसि ४. २३, २.
कल्पयस्व १८. १, १३.
कल्पयात् ३. ४, ६.
कल्पयाति ७. १०९, १; १८. ३, ५९; १९. ५९, ३.
कल्पयामि १२. २, ३२; १८. ४, ५२; १९. २७, ४.
कल्पयावहै २०. १२६, २१.
कल्पयित्वा १३. १, ५२; ५४.
कल्मलिः १५. २, ५; १३; १९; २५.
कल्माषऽग्रीवः ३. २७, ५.
कल्माषऽग्रीवाय १२. ३, ५९.
कल्याणि ६. १०७, ३; ४; १३९, ३.
कल्याणी ५. १७, १२; १८; १०. ८, २६.
कल्याण्यै ६. १०७, ३.
कवचऽपाशैः ११. १२, २२.
कवची ११. १२, २२.
कवयः ३. १७, १; ५. १, ६; ८. ९, १७; ९. २, ५; ४, ८; १४, ६; १३. १, २३; ४०; १८. १, १७; २, १८; १९. ५३, १; २०. ११, ७.
कवयः ४. २७, ३; १८. ३, १९.
कवये १९. ३, ४.
कविः ४. १, ७; ५. १, ४; ५; १२, १; १३, १; ८. ३, २०; ९. १४, १५; १३. १, ११; १८. ३; ६३; २०. ७७, ३.
कविऽक्रतुम् ७. १५, १.
कविऽतरः ५. ११, ४.
कविऽभिः ४. २६, ३; ९. ३, १९; १८. ३, ४७.
कविऽयमानः ९. १४, १८.
कविऽशस्ताः १८. १, ६०.
कविऽशस्तानि ५. १, ९.
कवीन् ९. १४, ७.
कवीनाम् ६. ४७, ३; ७. २३, १; १४. १, ५३.
कवे १२. १, ६३; २०. २४, ६.
कव्यऽवाहनाय १८. ४, ७१.
कव्यैः १८. १, ४७.
कशा ९. १, २१.
कशाम् ९. १, ५.
कशायाः ९. ११, २२.
कशिपुऽउपबर्हणम् ९. ६, १०.
कशिपुने ६. १३८, ५.
कशोकाः ५. २, ४; २०. १०७, ७.
कश्मशम् ५. २१, १.
कश्यप ८. ९, ७; १३. ३, १०.
कश्यपः ४. ३७, १; ८. ५, १४[२]; १८. ३, १५; १९. ५३, १०.
कश्यपम् ४. २९, ३.

कश्यपस्य १. १४, ४; २. ३३, ७; ४. २०, ७; ५. २८, ७; १७. १, २७; २८; २०. ९६, २३.
कश्यपाः १३. १, २३.
कष्कषासः ५. २३, ७.
कसर्णीलम् १०. ४, ५; १७.
कसन्तु ११. ११, २१.
कसाम्बु १८. ४, ३७.
कस्मात् ८. ९, १; १०. २, २; ९; ७, २[३].
कस्मिन् १०. ७, १[३]; ३[४]; ११. १०, १०; १२. ४, १४.
कस्मै ३. २९, ७; ४. २, १; २; ३; ४; ५; ६; ७; ८; १२. ४, ७.
कस्याः १२. ४, ४३.
कस्ये १८. ३, १७.
काः ५. १३, ९; ८. ९, २५; ११. ६, १७.
काकुदः २०. ७१, ३.
काकुदम् २०. ९२, ९.
काचित्ऽकरम् २०. १२६, १३.
काटम् १२. ४, ३.
काणया १२. ४, ३.
काण्डम् १२. ३, ४५.
काण्डिनीः ८. ७, ४.
काण्डैः १२. ३, ४२.
काण्वस्य २०. १३९, ३; १४०, ४.
कानि १९. ९, १३; ६४, ३.
कानीनः ५. ५, ८.
कान्दाऽविषम् १०. ४, २२.
काबवम् ३. ९, ३; ५.
काबवस्य ३. ९, ४.
कावेरकः ८. १४, ११.
काम॑ ३. २९, ७.
काम ९. २, ३[२]; ४[२]; ५; ९; १०; १६; १७; १८; १९; २०; २१; २२; २३[२]; २४; २५; १९. ५२, १; २; ५.
कामः ३. २५, २; २६, २; २९, ७[४]; ६. ३६, ३; ९. २, ७; ११; १९; ११. ३, ३; १८. १, ८; १९. ४, ४; ५२, १; ४; २०. १४३, ७.
कामऽज्येष्ठाः ९. २, ८.
कामऽदुघः ८. ९, २.
कामऽदुघा ४. ३४, ८; ९. ५, १०; ११. १, २८; १२. १, ६१.
कामऽदुघाः ९. ५, २५; १८. ४, ३३.
कामऽप्रः ११. ९, ८.
कामऽप्रेण १०. ९, ४.
कामम् ३. २१, ४; ४. ३९, २; ४; ६; ८; ९. १, ९; २, १; २; २४; १३. १, ५; २०. १५, ५; १७, २; २१, ३; ३१, २; ५८, २; ७६, ५; ८९, ६; १२२, ३.
कामऽसूता १८. १, १२.
कामम्ऽकामम् १८. ४, ५.
कामयन्ते ४. २४, ५.
कामयमानाः १९. ५२, ५.
कामयामहे १२. १, ४०; १९. ३२, ८.
कामये ४. ३०, ३.
कामये ६. ४५, १,
कामऽशल्याम् ३. २५, २.
कामस्य ३. २५, १; ३; ६. १३९, ५; ९. २, ६.
कामाः ११. ९, १३; १२. ३, ३६; ४, १९; १४. २, ५; १९. ४२, ३.
कामात् ९. १३, ८.
कामान् ३. १०, १३; २९, २; १२. ४, ३५; ३६; २०. ९६, ५; १००, १.
कामाय ३. ८, ४; २९, ७; ५. ३, ३; १२. ४, २६; २०. ३१, २.

कामिना २. ३०, २.
कामिनी १. ३४, ५; २. ३०, १; ६. ८, १; २; ३.
कामिनीः ३. ८, ४.
कामेन ३. २९, ७; ५. ११, २; ६. ९, १; १३९, २; ४; ११. ९, १३; १९. ५२, १; ३; ४.
काम्युः १९. ३९, ९.
काम्यम् २०. ५१, ३.
काम्यां २०. २६, ५; ४७, ११; ६०, ६; ६९, १०; ७१, ६.
काम्यैः २०. ४०, २; ७०, ४.
कायम् १९. ५७, ४.
कारम् २०. ७५, ३.
कारवः ७. ७७, १; २०. ९८, १; ११०, १.
कारवे २०. २१, ६.
कारुः २०. २५, ६.
कारू इति ५. १२, ७.
कारून् २०. ७७, ३.
कार्यस्य ३. २४, ५.
कार्शनः ४. १०, ७.
कार्षीवणाः ६. ११६, १.
कार्ष्णम् ११. ७, ६.
कालः १३. २, ३९; १९. ५३, १; २^{२}; ५^{२}; ६; ८; ९; १०^{२}; ५४, ३; ४; ५.
कालकाञ्जाः ६. ८०, २.
कालम् १९. ५३, ३.
कालात् १९. ५३, १०^{२}; ५४, १^{२}; ३^{२}.
काले ७. ५२, ६; १९. ५३, ३; ५; ६^{३}; ७^{३}; ८^{३}; ५४, १; २; ४^{२}; ५; २०. ८९, ९.
कालेन १९. ५३, ७; ५४, १; २^{२}.
काव्यः ४. १, ६; २०. २५, ५.
काव्यम् ९. १५, ९; १०. ८, ३२.
काव्यम् ४. २९, ६.
काव्येन ५. १, ५; ११, २; ३; ८. ३, २०; २०. ७६, ६.
काव्यैः २०. १२५, ५.
काशयामि १४. २, १२.
काशिना ८. ४, ८.
काष्ठासु २०. ९८, १.
कासः १. १२, ३.
कासम् ५. २२, ११.
कासा ५. २२, १०.
कासिकया ५. २२, १२.
कासिका ११. २, २२.
कासे ६. १०५, १; २; ३.
काहाबाहम् ९. १३, ११.
कितवम् ७. ११४, ३.
कितवान् ७. ५२, १.
किम् ४. २६, ६; ५. ११, ५^{२}; १३, ७; ६. ४५, १; ५१, ३; ५७, ३; ७१, १; ७. ५८, ६; ८; ७३, १; १११, १; ८. ४, १४; ९, २५; ९. १४, ७; १५, १८; १०. १, २०; ५, २२; २३; ७, ३७; ८, १६; ११. ३, २४; ६, ४; ११, १३; १३. १, ५५; ३, २३; १४. २, १९; १५. ३, १; १८. १, १२^{२}; ३३; २, २४; ३२; ३, ४१; १९. ६, ५^{३}; ४८, ३^{३}; २०. ३६, ४; ८९, ३; १२६, ३; ८^{२}.
किमीदिनः १. ७, ३; २८, १; २; ४. २०, ५; ८. ४, २३; ६, २१; २५; १२. १, ५०.
किमीदिनः २. २४, १; २; ३; ४.
किमीदिनम् १. ७, १; ४. २०, ८; ८. ३, २५.
किमीदिनीः २. २४, ५; ६; ७; ८.

किमीदिने ८. ४, २.
किमीदी ४. २८, ७.
किम्ऽकराः ८. ८, २२.
कियत् १०. ७, ८; ९.
कियता १०. ७, ८; ९^{२}.
कियतीः ८. ७, १३.
कियेधाः २०. ३५, ६; १२.
किर ३. २४, ५; २०. ९८, २.
किल १. ३४, ४; ४. ७, ३; १८. १, १९; ४८^{२}; २०. ३४, १८.
किलासऽनाशनम् १. २४, २.
किलासऽभेषजम् १. २४, २.
किलासम् १. २३, १; २; २४, २.
किलासस्य १. २३, ४.
किल्बिषम् ५. १९, ५; १२. ३, ४८.
किल्बिषाणि ६. ११८, १; २.
किशोराः १२. ४, ७.
कीकसाः ७. ८०, ३; ९. १२, ५; १३, १४; ११. १०, १५.
कीकसाभ्यः २. ३३, २; २०. ९६, १८.
कीटेभ्यः ९. ४, १६.
कीनाशः ४. ११, १०.
कीनाशाः ३. १७, ५; ६. ३०, १.
कीरये २०. १७, १२; ८७, ७.
कीरिम् २०. ९१, ११.
कीरेः २०. ३४, ६.
कीर्तयाः ७. ३८, १; ३९, ४.
कीर्तिः १२. ६, ३; १३. ५, १; ६, १; १५. २, ८^{२}; १४^{२}; २०^{२}; २८^{२}.
कीर्तिम् ५. २०, ९; ९. ८, ५; १०. ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; १९. ६३, १; ७१, १.
कील्याः १०. ६, २७.

कीलालऽऊध्नी १२. १, ५९.
कीलालः ७. ६२, ५.
कीलालम् ४. ११, १०.
कीलाले ६. ६९, १.
कीलालेन ४. २६, ६; २७, ५; १०. ६, २५.
कुकुन्धाः ८. ६, ११.
कुकूरभाः ८. ६, ११.
कुक्षिः ७. ११६, १; ९. १२, १२; २०. ७१, ३.
कुक्षिऽभ्याम् २. ३३, ४; २०. ९६, २०.
कुक्षिलाः ८. ६, १०.
कुक्षी इति २. ५, ४; ४. १६, ३; ९. ५, २०; १०. ९, १७; २०. १२६, १४.
कुक्ष्योः २०. ४, २.
कुचरः ७. २७, २; ८९, ३.
कुणपम् ११. १२, ४.
कुणपे ११. ११, १०; १२, ८.
कुण्डपाय्यः २०. ५, ७.
कुण्डृणाच्या २०. ७४, ६.
कुतः ८. ९, १; ४; ९. १४, १८; १०. २, १०^{२}; १४^{२}; ८, ४४; ११. १०, ८^{५}; १२^{४}.
कुत्सम् ४. २९, ५; २०. २१, १०; ३७, २.
कुत्सेन २०. ७६, २.
कुनखिना ७. ६७, ३.
कुबेरः ८. १४, १०.
कुमारः ३. १२, ३; ७; ४. ३७, ११; १०. ८, २७.
कुमारकः २०. ९२, १२.
कुमारम् १. ११, ५.
कुमारस्य ५. २३, २.
कुमाराः १२. ४, ८.
कुमारिका १०. ४, १४.
कुमारी १०. ८, २७.

कुमारीम् २. ३६, १.
कुमार्य्मि १४. १, ६३.
कुम्बम् ६. १३८, ३.
कुम्भः ३. १२, ७; १९. ५३, ३.
कुम्भम् ३. १२, ८; ११. १, १४.
कुम्भऽमुष्काः ८. ६, १५.
कुम्भऽमुष्कान् ११. ११, १७.
कुम्भान् ४. ३४, ७; १८. ३, ६८; ४, २९.
कुम्भी ११. ३, ११; १४; १२. ३, २३.
कुम्भीकाः १६. ६, ८.
कुम्भीम् ९. ५, ५; १२. ३, ५१.
कुम्भे १. ६, ४.
कुम्भेनऽइव १०. ८, १४.
कुम्भेभिः १९. २, २.
कुम्भ्यः ९. ६, १७.
कुयवम् २०. ३७, २.
कुरीरम् ६. १३८, ३; १४. १, ८.
कुरीरिणम् ६. १३८, २.
कुरीरिणि ५. ३१, २.
कुरु ५. ४, ६; ११. ११, १; १९; २२; २४; १४. २, २०.
कुरुते ९. ७, १; २; १५. ११, ९.
कुरुथाः ५. २२, ११.
कुरूटिनी १०. १, १५.
कुरूरवः ९. २, २२.
कुरूरुम् २. ३१, २.
कुर्कुरौऽइव ७. १००, २.
कुर्वताम् १९. ७, ४.
कुर्वतीम्ऽकुर्वतीम् ९. ५, ३२.
कुर्वते ७. ५६, १; ८. ६, ११; १४.
कुर्वते १२. १०, १; ३.
कुर्वन् ९. ५, ३२.
कुर्वन्तम् ९. ५, ३२.

कुर्वन्ति ८. १२, ६.
कुर्वाणाः १२. १०, २.
कुर्वे ६. १२९, १; ७. ३९, २; १२. ४, ६.
कुलऽपाः १. १४, ३; ७. ७५, २.
कुलायम् ९. ३, २०; १४. १, ५७.
कुलाये ९. ३, २०.
कुलिशेनऽइव २. १२, ३.
कुल्मलम् २. ३०, ३; ५. १८, ८.
कुल्मलात् ४. ६, ५.
कुल्या ११. ३, १३; १८. ३, ७२; ४, ५७.
कुल्याःऽइव २०. १७, ७.
कुल्यायाः ५. १९, ३.
कुवित् २. ३, २; २०. २४, २; ४; १२९, २.
कुवित्ऽसस्य २०. ७८, ३.
कुशिकासः २०. २४, ९.
कुषुम्भम् २. ३२, ६.
कुष्ठ ५. ४, १.
कुष्ठ ५. ४, ६; ९; १९. ३९, २; ९.
कुष्ठः ५. ४, १०; १९. ३९, १; ५; ६[२]; ७[२]; ८[२].
कुष्ठम् ५. ४, ३; ४; ५; ६. ९५, १; २.
कुष्ठस्य ५. ४, ८; ६. १०२, ३.
कुष्ठाः १९. ५७, २.
कुष्ठिकाः ९. ४, १६; १२, १०; १०. ९, २३.
कुसिन्धम् १०. २, ३.
कुसिन्धे १०. २, ५.
कुसूलाः ८. ६, १०.
कुह २०. ३४, ५.
कुहचित्ऽविदे २०. ८२, २.
कुहूः ७. ४९, २.
कुहूम् ७. ४९, १.
कूजन्तौ ७. १००, २.
कूटम् ८. ८, १६.

कू॒ट्या॑ १२. ४, ३.

कू॒द्य॑म् ५. १९, १२.

कूपे॑ ५. ३१, ८.

कू॒र्मेभ्य॑ः ९. ४, १६.

कूल्व॑जम् १२. ७, १; १०, ७.

कृ॒क॒दा॒श्व॑म् २०. ७४, ७.

कृ॒क॒वाकौ॑ ५. ३१, २.

कृ॒का॑टम् ९. १२, १.

कृ॒ण॑वः १८. २, ५.

कृ॒ण॒वः ५. १, ८.

कृ॒ण॑वत् २. ९, ५; ५. ८, ७.

कृ॒ण॒व॒त् २. ३५, १; ३. १, १; २, १; ५. २, ८; ६. १११, १; ११६, २; १२. ३, १०; १९. २७, १०; ३३, ५; २०. १०७, ११.

कृ॒ण॑वन् १८. १, ११.

कृ॒णवा॑म ६. २७, १.

कृ॒ण॒वा॒म॒ १२. ३, ४९.

कृ॒णु॒ २. १९, ५; २०, ५; २१, ५; २२, ५; २७, १; २; ३; ४; ५; ६; ३६, ६[२]; ३. ५, ६; ७; २२, ३; ४. २२, १; ५. ६, १०; २९, २; ३; १३; ६. ९९, ३; १०८, ४; १२१, ४; १२९, २; ३; १४०, १; ७. १३, ३; १२. १, २३; २४; १४. १, ६१; १९. ३१, १३; ३२, ८; ४७, ८; ५०, १; ६२, १[२].

कृ॒णु॒त ११. १, २.

कृ॒णु॒त॒ १. ३०, ३; २. १३, २; २३, ५; ३. ९, १; ६. ५५, ३; १२३, २; १२. २, ३४; १८. ४, ३७; १९. २४, ४; २०. ९१, ११.

कृ॒णु॒तम् ६. ५४, २; १४१, ३.

कृ॒णु॒त॒म् ३. २५, ६; ६. ५०, १.

कृ॒णु॒ताम् २. २८, २; ४; ३. ३, ४; ७. ६४, १.

कृ॒णु॒ते॒ १. ३५, २; ६. २७, ३; ८. ३, २४; ९. ४, १९; ११. ७, ३; १०; १५; १२. ४, ६; ३०[२]; १३. २, २८; ४२; २०. ८९, ४; १२३, २.

कृ॒णु॒थ॒ ४. २१, ६[२]; ६. २२, २.

कृ॒णु॒ध्व॒म् १९. ५८, ४[२]; २०. ७३, ३.

कृ॒णु॒षे ३. ६, ६; ८. २, १६.

कृ॒णु॒षे॒ ५. १, २; १९. ४९, ४.

कृ॒णु॒ष्व २०. ९३, १.

कृ॒णु॒ष्व॒ ३. ४, ४; ४. २०, ५; ७. ३५, १; ३७, १; ७७, १०; १०. १, १६; १२. ४, २९; १४. २, ५०; १८. १, १६; ३, ८; १९. ४५, ५.

कृ॒णु॒हि २०. ८, १.

कृ॒णु॒हि॒ ३. १, ४; ४. २२, ३; ५. ११, ११; १२, २; २७, १२; ७. ९, १; ११. १, ३१; २०. १२५, २.

कृ॒णो॒त॒ ५. ३, ६.

कृ॒णोति॑ २. ३६, ३; ६. २९, १; ८. ३, ८; ६, ९; ९. १३, ४[२].

कृ॒णो॒ति॒ ९. १०, १; ४; ६; ८; १२. ४, २५; १८. १, ५३; ३, ५४; २०. ९६, ३.

कृ॒णोतु॑ ६. ८३, १; ८. ६, १८; ९. २, ७; १९. ४४, ३.

कृ॒णो॒तु॒ १. ११, १; ३. १५, ४; ४. ४, ३; ६. ४०, १; २[२]; ५३, ३; ५८, १[२]; ७१, १; २; ७२, १; ७३, ३; ७८, ३; १०४, ३; १०६, ३; ७. ३३, १; ३४, १; ५३, १; ९१, १; ९६, १; १२३, १; ८. ८, २; ४; ९. ४, २; १५, २४; १०. ६, ३१; ९, २६; ११. १, ६; १२. १, १; २१; २२; ४१; ४३; १४. १, ४७; ४९[२]; २, १२; ३९; ७५; १८. ३, १२; ५२; ५५;

६१; १९. ३१, १४; २०. १७, ११; ९५, १; ८९, ११; ९४, ११; १२९, ६.
कृणोर्मि २. ३६, २; ३. ९, २; २३, ५; ४. १८, १; ६. ९, २; १११, २; ३; ११९, १[२]; ८. २, ५; ११; ६, ३; १२. २, ३२; १४. १, ५८.
कृणोमि १. २५, ४; ३०, ४; २. २, ४; ३, १; १०, १; २; ३; ४; ५; ६; ७; ८; ३. ८, ६; ३०, १; ५; ७; ४. ३०, ३; ५; ५. १, ५; २८, ११; ३०, ५; ८; ६. २०, ३; ९३, २; ९४, २; ७. ३६, ३[३]; ८. १, ६; २, १३; १९; ७, ५; २२; ९. २, १९; २०; २१; २२; २३; २४; १४. २, ३४; १९. ३०, ४; २०. ७३, १.
कृणोर्षि ५. २२, २; ६. २०, ३; ३०, २; ७. ५८, ४; १३. ७, १५; २०. ११४, २.
कृण्मः ६. ५, ३; ७. ८१, १.
कृण्मः १. १३, ३; ३. ३०, ४; ५. ७, २; ८. २, १६; २१; ९. ३, १२; ११. २, ३; ४; १४. १, ६३; २, ३५.
कृण्मसि १९. ५२, ५.
कृण्मसि ४. ३१, ४; ५. २८, १३; ८. २, १०.
कृण्महे १९. ६८, १.
कृण्वत् ५. २८, १४.
कृण्वती १४. २, ६०.
कृण्वतीः १४. २, ६१.
कृण्वते ८. ५, ७.
कृण्वन् ५. १, ७; ६. ७२, १; १२. १, ५१; १८. १, २९; १९. ३३, २; २०. २६, ६; २८, २; ३९, ३; ४७, १२; ६९, ११.
कृण्वन्तः ३. १०, ५; ९. २, ८; १८. २, २२; २९; ४, १२; १३.
कृण्वन्तः १४. २, ५९.
कृण्वन्ति १. ३३, ३.
कृण्वन्तु २. १३, ४; २०. १९, २.
कृण्वन्तु ३. ९, ३; ६. २३, २; ३; ९१, ३.
कृण्वाथाम् १४. २, ३७; ३९.
कृण्वानः २. २९, ३.
कृण्वानाः १. १३, ४; ५. ८, ६; ११. १२, १७.
कृण्वानाम् ४. ३८, १.
कृण्वे ५. ८, ८; ११. १, २८; ३१.
कृण्वे ७. १०५, १; ९. ३, १५.
कृतऽअकृतम् १९. ९, २.
कृतऽआगसः १२. १०, १४; ११, ४.
कृतः ४. ६, ७; ५. २०, ८; ६. १५, ३; ९. ३, २; २०. ४७, २; १३७, १३.
कृतऽद्विष्टा ७. ११८, १.
कृतम् ३. ९, २; ४. २६, ७; ३८, ३; ५. ५, ४; ९, ८; ६. ९, ३; ११, १; ७२, २; ९७, २; ७. ४३, १; २; ५२, २; ३; ५; ८; ९. २, १६; १०. १, ३२; १३. ७, १२; १४. २, ६२; ६५; १९. ९, १२; ७२, १; २०. १३, २; १७, ५; १३९, ५; १४३, ९.
कृतम् १९. १६, १; २७, १४; ४४, १.
कृतम्ऽइव ७. ५२, ६; २०. ८९, ९.
कृतऽवीर्यः १७. १, २७.
कृतऽव्यधनि ५. १४, ९.
कृतस्य १. २३, ४; ३. २४, ५; ७. ५२, ९.
कृता ५. १४, ७; १०. १, ३; ८, २६.
कृताः ४. ६, ७; १९. ६, १५.
कृतानि ४. ३८, १; २; ३; २०. ३४, ४; ८७, ५.
कृते ३. १७, २; २०. ३१, ४.

कृतेन ६. १२४, १.
कृत्तिकाः ९. १२, ३; १९. ७, २.
कृत्तीः ८. ६, ११.
कृत्तुम् २०. ४४, ३.
कृत्या ४. ९, ५; ५. १४, ५; ११; १२; १३; १२. ७, १; ९, १; १०, ७; १४. १, २५; २६.
कृत्याः ४. १८, ५; ५. १४, ५; ८. ५, २; ५; ६; ७; ९[२]; १०. १, ४; ६; ३०; १४. २, ४९; १९. ९, ९.
कृत्याऽकृत् ४. २८, ६.
कृत्याऽकृतः ४. १७, ४; १९, १; १०. १, ६; १९; ३१[२]; १९. ३४, २; ४५, १.
कृत्याऽकृतम् ५. १४, १; २; ४; ५; १०; १२; १३; ३१, १२; १०. १, ५.
कृत्याऽकृता १०. १, २; २४; ३२.
कृत्याऽकृते ५. १४, ३; ४; ५; ८; १०. १, २३.
कृत्याऽदूषणः १९. ३४, ४.
कृत्याऽदूषणम् १०. १, ९.
कृत्याऽदूषणीः ८. ७, १०.
कृत्याऽदूषिः २. ४, ६.
कृत्याभिः ८. ५, १५.
कृत्याम् ४. १७, ४; १८, २; ४; ५. ९, ८; १४, ३; ४; ६; ८; ३१, १; २; ३; ४; ५; ६; ७; ८[२]; १०. १, १८; ३, ४; १४. २, ६५; १९. ४५, १.
कृत्यै ५. १४, १०; ११. १२, ६.
कृत्ये १०. १, ७; १५; १७; २०; २१; २५; २६; २९; ३१.
कृत्रिमः १४. २, ६८.
कृत्रिमम् १९. ३४, ३.
कृत्वः ११. २, ९; १२. २, २९.
कृत्वरीः ४. १८, १.
कृत्वा ३. ३, ६; २५, २; ६; ४. ७, ३; १८, २; ३; ५. १७, ११; २२, ४; ६. १०३, ३; ८. ६, २६; ९, २; १०. १, ९; ९, ५; ६; २५; ११. ७, ९; १०, ११; १८; २९[२]; १२. २, ४; ४३; ५४; ४, २०; १३. १, ४७; ५२[२]; ३, १; १५. १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३; १८. २, ३३; ३, ४२; १९. ८, ६; ३०, १.
कृधि २०. ८९, ७.
कृधि १. २, २[२]; १३, २; २४, ३; २६, ४; ३४, १; २. २७, ७; ३. १८, २; ५. ४, ६; ९; ५, ४; ८, ६; ७; ६. ५, १; २; ४०, ३; ६५, १; ६७, ३; ७४, ३; ७७, ३; ९५, ३; १०६, २; १२८, ३; १३६, २; १३८, १; २[२]; १३९, ३; १४१, २; ७. २१, २; २७, ३; ५२, ४; ८६, ३; ८. ५, १७; ११. १२, १७; १७. १, ७; १८. २, ९; १९. ८, ६; १५, १; ३२, ६; २०. ३२, १; ८०, २.
कृधुऽकर्णी ११. ११, ७; १२, ७.
कृन्त १९. २८, ८[४].
कृन्तती १. २७, २.
कृन्तत्रम् २०. १२६, २०.
कृपणाः ११. १०, २८.
कृपमाणस्य ५. १९, १३.
कृपा १८. ४, ५९; २०. ६७, ३.
कृपात् ७. १५, २.
कृपे २०. १२०, २.
कृशऽगुः ४. १५, ६.
कृशनः ४. १०, १; ३.
कृशनम् ४. १०, ७.

कृशनेमिः २०. १६, ११.
कृशम् ४. २१, ६; ६. १०१, २.
कृशस्य २०. ३४, ६.
कृषतु ३. १७, ६.
कृषते १२. २, ३६.
कृषिम् ३. १२, ४; ८. १३, ११; १२; १०. ९, ३४; ६, १२.
कृषिऽसंशितः १०. ९, ३४.
कृष्टयः ३. २४, ३; १२. १, ३; ४; ४२; २०. ६८, ६; १०७, १.
कृष्टऽराधिः ८. १३, १२.
कृष्टीः २०. ३७, १; ६९, १; ७०, १४.
कृष्टे १०. ६, ३३.
कृष्णऽअजिनम् ९. ६, १७.
कृष्णः ७. ६६, १; २; ८. ६, ५; १२. ३, १३; १८. ३, ५९; २०. १३७, ७.
कृष्णऽकर्णः ५. १७, १५.
कृष्णऽद्रम् ९. १२, ४.
कृष्णम् ६. २२, १; ९. १५, २२; ११. २, १८; १२. १, ५२; १३. ३, ९; २०. १२३, २; १३७, ८.
कृष्णऽवर्तने १. २८, २.
कृष्णऽशकुनेः १९. ५७, ३.
कृष्णा ६. ८३, २; ७. ७८, १; १२. २, ५३.
कृष्णाः ६. ४९, ३.
कृष्णाः ५. २३, ५; ८. ७, १; ११. २, २; १८. ४, ३४.
कृष्णात् ५. ३०, ११.
कृष्णाम् १२. १, ११; ३, ५४.
कृष्णायाः १३. ३, २६.
कृष्णे १. २३, १.
कृष्णौ ५. २३, ४.
कृष्या ११. ४, १०.
कृष्याः २. ४, ५; ८. २, १९; १०. ५, ३४; १२. २, ३७.
कृष्व २०. ९४, ४.
के ४. २२, ६; ५. २२, ५; ६. ५०, ३; ७. १३, २; १२२, १; १०. ७, ३८; ११. १०, १[२]; १९. ६, १२.
केतवः ११. १२, ७; १३. २, १; १६; १८; २०. ४७, १३; १९.
केतुः ७. १२, १; ८६, २; १०. ८, १३; ११. ६, २२; १३. २, ३४; १४. १, २४; २०. ३०, ४; १०७, १३.
केतुना १३. २, ९; ३१; १८. ३, ६५.
केतुऽभिः ११. १२, १; २; १३. ३, २३.
केतुम् १०. २, १२; २०. ११, ४; २६, ६; ४७, १२; ६९, ११.
केतुऽमत् ६. १२६, २.
केतुमती इति केतुऽमती ८. ९, १२.
केतुऽमन्तः ३. १९, ६; १३. १, २४.
केतुऽमान् १३. २, २८.
केतून् ६. १०३, ३; १०. १, ३२.
केन ५. ११, २[२]; १०. २, १[६]; १६[४]; १८[४]; १९[४]; २०[४]; २२[४]; २४[३]; १८. १, ५२.
केऽनिपानाम् २०. ९४, ४.
केनो इति २०. ९७, ३.
केपयः २०. ९४, ६.
केवलः ७. ३८, १; ३९, ४; २०. ३९, १; ७०, १६; ८७, ९.
केवलम् ३. १८, २; ४. २२, ७; १०. ७, ३६; ८, १; ११. ७, १०; १५; २०. १५, ६; ३२, ३.
केवली ३. २५, ४; ८. ९, २४; १९. ४, २.
केवलीः ७. ९९, १.
केवलौ ९. ४, १२.

केशः ६. १३६, ३.
केशऽदृंहणीः ६. २१, ३.
केशऽवर्धनीः ६. २१, ३.
केशऽवर्धनीम् ६. १३७, १.
केशऽवाः ८. ६, २३.
केशऽश्मश्रु ८. २, १७.
केशाः ६. ९, १; १३७, २; ३; १५. २, ५; १३; १९; २५; १९. ६०, १.
केशान् ५. १९, ३; ११. १०, ११; १२; १४. १, ५५; १९. ३२, २.
केशिनः ९. १५, २६; ११. २, १८; १४. २, ५९.
केशिना २०. ३, २; २३, ९; २९, २; ३८, २; ४७, ८.
केशिनीः १२. १०, २.
केशिनीभ्यः ११. २, ३१.
केशी ८. ६, ५.
केशेभ्यः ६. ३०, ३; १३६, १.
केशेषु १. १८, ३.
केश्यम् १४. २, ६८.
केसरऽप्राबन्धायाः ५. १८, ११.
कैरात ५. १३, ५.
कैरातिका १०. ४, १४.
कोकः ५. २३, ४.
कोकम् ८. ६, २.
कोकऽयातुम् ८. ४, २२.
कोपयत् २०. ९४, ८.
कोशः ९. ३, २०; १०. २, ३१; ११. २, ११; १४. १, ६.
कोशःऽइव ४. १६, ७.
कोशम् ४. १५, १६; १८. ४, ३०; २०. ८, ३; ८९, २.
कोशाः १३. ४, १०.
कोशात् १९. ७२, १.
कोशान् १०. ७, १०.
कोशे ९. ३, २०; १०. २, ३२.
कौमारः १२. ३, ४७.
क्नदिऽवतः ७. ९५, ३.
क्याम्बूः १८. ३, ६.
क्रक्षमाणम् २०. ४२, २.
क्रतुः ८. ९, २२; २०. १८, ५.
क्रतुना १३. २, १०; २०. ३४, १.
क्रतुऽभिः ८. ३, १; १३. ३, २३.
क्रतुम् ५. २, ३; १८. १, २०; ३, १८; ६७; २०. ७९, १; १०६, १; १०७, ६.
क्रतुऽविदम् २०. ६, २; ७, ४.
क्रतौ १. ३४, २; ३. २५, ५; ६. ९, २.
क्रत्वा ४. ३१, ६; ३२, ५; २०. ५४, १; ७६, ७.
क्रत्वे ६. १९, २; १८. २, २३.
क्रन् ७. ८७, ३; ८. ६, २५; १४. १, ३२; १९. २०, ४.
क्रन्द ४. १५, ६; ५. २०, ७; २१, ४; ५; ६.
क्रन्दः ११. २, २२.
क्रन्दत् २०. ९४, ८.
क्रन्दय २. ३६, ६; ६. १२६, २.
क्रन्दसी इति ४. २, ३; २०. ३४, ८.
क्रन्दाय ११. २, ३; ६, २.
क्रमः १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५.
क्रमताम् ९. ५, १; ३; ८.
क्रमते ७. १५, ४.
क्रमध्वम् ४. १४, २.
क्रमस्व ४. ४, ७; ६. १०१, ३.
क्रमस्व ४. ८, ४; ७. २७, ३; १८. ४, ६; २०. ८५, ४.

क्रमान् **८.** ९, १०.
क्रमुः **२०.** ७९, २.
क्रमे **१०.** ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; **१९.** १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
क्रविः **८.** ६, २३.
क्रविषा **८.** ३, १५.
क्रविष्णुः **८.** ३. ४.
क्रव्यऽअत् **३.** २१, ९; २८, २; **५.** २९, ८; ९; १५; **८.** १, १२; ३, ४; **१२.** २, ४; ७; ३५; ३६; ३७; ३८; ४३; ५०; ५२; ५३; ३, ४३; ९, ३; ११, ११.
क्रव्यऽअर्दः **२.** २५, ५; **४.** ३६, ३; **५.** २९, ११; **८.** २, १२; ३, २; १८; **११.** १२, ३.
क्रव्यऽअर्दम् **३.** २१, ८; ९; १०; **५.** २९, १०; ३१, ९; **८.** २, ९; ६, ६; **१२.** २, ८; ९; १०; १५; १६; ३९; ४२; ४३; **२०.** ९६, १२.
क्रव्यऽअर्दा **११.** १२, १८; **१२.** २, ३४; ५१; **१३.** १, २९.
क्रव्यऽअर्दे **८.** ४, २.
क्रान्तम् **१०.** ७, ३८.
क्राम २. ११, १; २; ३; ४; ५; **८.** १, ४; **९.** ५, ६; **१०.** १, १४; **२०.** ९६, २४.
क्रामतम् **७.** ५५, २.
क्रामति **१२.** ५, ६.
क्रामन्ति **१२.** ६, ५.
क्रिमयः २. ३१, ५; ३२, १; ५; **५.** २३, ५; १२.
क्रिमयः २. ३२, ३; **५.** २३, १०.
क्रिमिः **२.** ३२, ४; **५.** २३, ७; ११; **११.** ११, १०; **१२.** १, ४६.
क्रिमिम् **२.** ३२, २; **५.** २३, १; ३; ९.
क्रिमीणाम् **२.** ३१, ३; ५; ३२, ४; **५.** २३, ८; ११; १३[२].
क्रिमीन् **२.** ३१, १; २; ४[२]; ३२, १; ३; **५.** २३, २; ५; ६; १०.
क्रिमेः **२.** ३१, १.
क्रियते **३.** २९, ३; **८.** २, २५; **१९.** ५८, ६.
क्रियते **१८.** २, १; ३, ६४.
क्रियन्ते **२०.** २३, ३.
क्रियमाणम् २. १२, ६; **५.** २९, १; **१९.** ११, ४.
क्रियमाणायाः **३.** ७, ६.
क्रीडन्तीः **९.** ४, २४.
क्रीडन्तौ **७.** ८६, १; **१३.** २, ११; **१४.** १, २२; २३.
क्रीणीते **१२.** ४, २.
क्रीत्वा **३.** १५, २.
क्रुद्धः **१०.** १०, १०; ११; **१२.** ८, ९; **१३.** ३, ६; **२०.** १७, ८.
क्रुद्धस्य **१३.** ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.
क्रुद्धा **१२.** ४, ३७.
क्रुद्धाः **१२.** २, ५.
क्रुधः **११.** २, १९; २०.
क्रुध्यति **४.** ३६, १०.
क्रूरम् **५.** १९, ५; **६.** ४९, १; **१८.** ४, ८३; **१९.** ९ १४; ५६, ५.
क्रूराणि **१२.** ७, ३.
क्रूरैः **१६.** ७, २.
क्रोडः ९. ४, १५; १२, ५.
क्रोडौ **१०.** ९, २५.

क्रोधः ९. १२, १३.
क्रोधम् ४. ३८, ४.
क्रोधयन्ति ४. ३६, ९.
क्रोशताम् ८. ८, २१.
क्रोशतु ११. ११, ७; १२, ७.
क्रोशन्तु ५. २१, ९.
क्रोष्टारः ११. २, ११.
क्रोष्टे ११. २, २.
क्लन्दाः २. २, ५.
क्लीबं ६. १३८, ३.
क्लीबम् ६. १३८, १; २; ३.
क्लीबऽरूपान् ८. ६, ७.
क्लीबाःऽइव ८. ६, ११.
क्लृप्तः १०. १०, २३.
क्लृप्ताः ८. ९, १५.
क्लोमा १०. ९, १५.
क्लोम्नः २. ३३, ३; ९. १३, १२; २०. ९६, १९.
क्व ९. १४, ४; १७; १०. २, २; ७, १[2]; ४[2]; ५[2]; ६; ८, ७; ४१; १३. १, ४१; १४. १, १४[2]; १५. ११, २; ३; २०. १२६, २२.
क्वऽइव १०. ८, ३९.
क्षणिष्ठाः १०. १, १६.
क्षत्ता ५. १७, १४.
क्षत्तारम् ९. ११, १.
क्षत्तारौ ३. २४, ७.
क्षत्रऽभृत् ७. ८९, १.
क्षत्रम् २. १५, ४; ३. ५, २; १९, १; ५; ५. १, ८; १८, ४; ९. १२, ९; ६. ५४, १; २; ९७, २; ९८, २; ७. ८९, २; १०. २, २२; २३; ३, १२; ११. ९, १८; १०, २०; १२. ६, २; १५. १०, ३; ४; ५; ७; ११; १६. १, १३.
क्षत्रऽयोगैः १०. ५, २.
क्षत्रऽवर्धनम् १०. ६, २९.
क्षत्रस्य १९. ३०, ४.
क्षत्राणाम् ४. २२, २.
क्षत्राणि ७. ८३, २.
क्षत्राय १५. १०, २; १९. २४, २.
क्षत्रियः ६. ७६, ४; ७. १०८, १; १२. ९, ८.
क्षत्रियम् ४. २२, १; ८. ४, १३.
क्षत्रियस्य ५. १७, ३; १२. ५, ५; ६, ५.
क्षत्रियेण ६. ७६, ३; १२. ९, ६.
क्षत्रे १९. २४, २.
क्षत्रेण २. ६, ४; ७. ८७, २; ३; १२. ३, ५१; १८. २, ६०.
क्षदामहे १०. ६, ५.
क्षपाऽवान् २०. ७६, १.
क्षमा ६. ५७, ३.
क्षमाम् १२. १, २९.
क्षमि १८. १, १; १९. ५, १.
क्षयः २०. १०६, ३.
क्षयत् २०. ९२, ८.
क्षयति ५. २, ८; २०. १०७, ११.
क्षयन्तीः १. ५, ४.
क्षयम् २०. ६, ४; ६७, १.
क्षयाय १. ५, ३; ७. २७, ३.
क्षये २०. १, २.
क्षयेम १९. १५, ४.
क्षर ७. ११४, ४.
क्षरत् ५. १, ३.
क्षरन्ति ४. ३५, ५; १२. १, ९.
क्षरन्ति ७. १९, २; ५९, २; ९. १५, २१; ११. २, २४; १३. १, ४२.

क्षरन्तु ८. २, १४; १२. १, ३०.
क्षवम् १९. ८, ९.
क्षापय १२. १०, ९.
क्षापय १२. १०, ९.
क्षापयति १२. ९, ६.
क्षाम् ५. १, ९; १८. १, ३९; १९. ४९, ८; २०. ३६, ८.
क्षाम १८. ३, २१.
क्षामः २०. ९२, १९.
क्षामत् ७. ६५, १.
क्षामा १८. १, २९.
क्षिणाति ३. २८, १; २; १२. २, ३५.
क्षिणामि ३. १९, ३.
क्षिणीहि १०. ३, १५; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.
क्षिणोमि ६. १४, २.
क्षितऽआयुः ३. ११, २; २०. ९६, ७.
क्षितिः ११. ९, २५; १०, ४; २६; १२. ७, ५; ८, ६.
क्षितीनाम् ६. ३४, १; २०. ११, २; ७०, १५; ८७, १.
क्षिपसि ९. १, १०; २०.
क्षिप्तऽभेषजी ६. १०९, १.
क्षिप्तस्य ६. १०९, ३.
क्षिप्रऽधन्वने ११. ६, २३.
क्षिप्रम् ८. ८, ४; ११. १, १३; १२. १, ३५; १०, १; ३; ४.
क्षिय ६. १२१, ४.
क्षियति १०. २, २२; २३; ११. ९, १६.
क्षियन्तम् १३. २, ४३; २०. १६, ८; ३४, ११.
क्षियन्ति १३. ३, १.
क्षियन्ति ४. ३०, ४.
क्षियेम ६. ११७, ३.
क्षीयते १२. ९, ७.
क्षीरम् २. २६, ४; ५; ५. १९, ५; ८. ३, १५; ९. ८, ९; ९, १; १४, ५; १०. ९, १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १०, ८; १०; ११.
क्षीरऽवान् १८. ४, १६.
क्षीरस्य १. १५, ४.
क्षीरिणीम्ऽइव ७. ५२, ९.
क्षीरे ५. २९, ७; १८. २, ३०.
क्षीरेण ४. ३४, ६; ७.
क्षुणवानः ५. २०, १.
क्षुत् ९. १२, १२.
क्षुद्रेभ्यः १९. २२, ६; २३, २१.
क्षुधः ११. १०, २१.
क्षुधः २०. १७, ३.
क्षुधत् २. २९, ४.
क्षुधम् ७. ५२, ७; ८. ८, १८; १९. ३१, ११; २०. १७, १०; ८९, १०; ९४, १०.
क्षुधा ४. ७, ३.
क्षुधाऽमारम् ४. १७, ६; ७.
क्षुऽमति १८. ३, २३.
क्षुऽमती १८. १, २०.
क्षुऽमन्तः २०. १२२, १.
क्षुऽमन्तम् २०. ९, २; ४९, ५.
क्षुम्पम्ऽइव २०. ६३, ५.
क्षुरऽपविः १२. ७, ९; १०, ९.
क्षुरऽभृष्टिना १२. ११, ५.
क्षुरेण ६. ६८, १; ३; ८. २, १७.
क्षुल्लकाःऽइव २. ३२, ५; ५. २३, १२.
क्षेति २०. २५, ३.

क्षेत्रऽसातौ २०. ३७, ३.
क्षेत्रस्य २. ८, ५; १२, १; १९. १०, १०; २०. १४३, ८.
क्षेत्राणि २. २९, ३; १४. २, ७.
क्षेत्रात् ११. १, २८.
क्षेत्राय ३. २८, ३.
क्षेत्रियऽनाशनी २. ८, २; ३; ४; ५.
क्षेत्रियम् २. ८, २; ३; ४; ५; ३. ७, १; २; ३; ६[२]; ७; ४. १८, ७.
क्षेत्रियस्य २. ८, १; ३. ७, ४.
क्षेत्रियाणाम् २. १४, ५.
क्षेत्रियात् २. १०, १; २; ३; ४; ५; ६; ७; ८; ३. ७, ५.
क्षेत्रे ४. १८, ५; ५. १७, १६; ३१, ४; १०. १, ४; १८; ४, ८; ११. १, २२; १२. १, ४३.
क्षेमः ११. ९, १३; १३. १, २७.
क्षेमम् ३. ३, ५; ४. १, ४; १९. ८, २[२].
क्षेमे ३. १२, १.
क्षेम्यः १२. २, ४९.
क्षेष्ट ४. ३४, ८.
क्षोणी इति २०. १०५, २.
क्षोणीः २०. ९, ४; ४९, ७.
क्षोणीःऽइव २०. १५, ४.
क्षोभणः १९. १३, २.
क्ष्विङ्काः ८. ३, ७.

ख

खड्गे ११. ११, १६.
खण्वखा३इ ४. १५, १५.
खदिर ८. ८, ३.
खदिरम् १०. ६, ६; ७; ८; ९; १०.
खदिरात् ३. ६, १; ५. ५, ५.
खनः १६. १, ३.
खनति १०. ४, १४.
खनन्ति २. ३, ३.
खनमानाः १९. २, ३.
खनामसि १. ३४, १; ४. ४, १; ६. १३६, १.
खनामि ३. १८, १; ७. ३९, १.
खनितारः ४. ६, ८.
खनित्रिमाः १. ६, ४; ५. १३, ९; १९. २, २.
खनिम् १६. १, ७.
खर्गलाऽइव ८. ४, १७.
खर्वऽवासिनीम् ११. ११, १६.
खर्विकाम् ११. ११, १६.
खलः ११. ३, ९.
खलऽजाः ८. ६, १५.
खल्वान्ऽइव २. ३१, १; ५. २३, ८.
खातम् ५. १३, १.
खाताः २०. ८८, ३.
खाद ८. ८, ३.
खादतः ६. ४९, २.
खादन्तः ५. १९, ३.
खादन्ति ८. ६, २३.
खादम् ९. ६, १२.
खानि १०. २, १; ६.
खार्लत्यम् ११. १०, १९.
खिद ४. २२, ७.
खिदति ११. ६, २१.
खिदामि ६. १०२, २.
खिद्वः २०. ३६, ४.
खिले ७. १२०, ४.
खिल्ये ४. २१, २.
खीलाः १०. ८, ४.
खुदत २०. १३७, २.
खृगलम् ३. ९, ३.
खे १४. १, ४१[३].

खैमखा३ई ४. १९, १९.
ख्यः २०. ५६, ६.
ख्यः २०. ५७, ३; ६८, ३.
ख्यन् १८. १, २.

ग

गच्छ ५. २२, १२; १८. २, ७.
गच्छ २. ३४, ५; ५. १४, १०^{२}; २२, ७; ६. ११३, २; ७. १०२, ५^{३}; १०. १, ८; ११. १, ३५; १२. ३, ५३; १४. १, २०; २, ७५; १८. २, ७^{२}; ४६; ३, ९; ४, ६; १९. २४, ५.
गच्छत १८. ३, ४४.
गच्छतः ४. ११, १०.
गच्छतम् १८. २, ५३.
गच्छतात् २. ३०, ३; ९. ३, १०; १८. २, १४; १५; १६; १७; १८; ५६.
गच्छताम् १८. २, १०; ३, ५८.
गच्छति ५. २३, ३; १०. ८, १६; ११. १०, २३; २०. १२६, १२.
गच्छति ३. १३, ६; ६. ७६, ४; ९. ९, १०; ११. १०, ३३^{२}; १२. ४, ३१; ३२; १५. २, ८^{२}; १४^{२}; २०^{२}; २८^{२}; ७, ३^{२}; ५^{५}; १०, ८; १०; ११, ७; ९; ११; १८. २, १; २०. २५, १; १२६, १०.
गच्छतु २. १२, ८; ७. १०३, १; ९. ५, १; ५; १२. २, ४; ८; १८. २, २३.
गच्छथः ४. २९, २; २०. १४०, १.
गच्छन्ति २. २५, ५; १०. ८, ३३.
गच्छन्तु १२. २, ४५; २०. १३७, ४.
गच्छासि २०. ११२, ३.
गच्छस्व १८. २, २१; ३, ५८.
गच्छात् ४. १, ७.
गच्छाति १८. २, ५.
गच्छान् १८. १, ११.
गच्छासि ५. ५, ६.
गच्छेम ६. १२१, १; ७. ८८, ४; ११. १, ८; ३६.
गणः १३. ४, ८.
गणाः ४. १३, ४; १९, ४.
गणेन १९. १३, ४; २०. ८८, ५.
गणेभ्यः १९. २२, १६.
गणैः १९. ४५, १०; २०. ४०, २; ७०, ४.
गत १८. १, ५१.
गतऽअसुम् १८. ३, २.
गतऽअसोः १८. २, ५९.
गतम् ७. ७७, २; ४.
गताः १०. १०, ३२.
गतान् १८. ४, ४१.
गतानाम् ८. १, ८.
गतुम् ६. ११८, १.
गत्वा २. ३६, ३; ४. १४, २; १२. ३, १३; १९. ८, ३.
गद ५. २२, ६.
गधि २०. ६४, १.
गन् ३. ४, १; १३. १, २.
गन्तम् २०. १३९, १.
गन्तवे ९. ५, १७.
गन्तारम् २०. ७१, १५.
गन्धः ११. ३, ८; १२. १, २३; २४; २५; १९. ३८, १.
गन्धम् ८. १४, ७; ८; १२. १, २४.
गन्धर्वऽअप्सरसः ८. ८, १५; १४, ५^{२}; ८; १०. ९, ९; ११. ८, ४; ९, २७; ११, १६; २४; १९. ५४, ४.
गन्धर्वऽअप्सरसाम् १९. ३६, ६.
गन्धर्वऽऋतुना १४. २, ३४.

गन्धर्वः २. १, २; २, १; २; ३; ४. ४, १; ३७, ११; १४. २, ३; ४; १८. १, ४.
गन्धर्वऽपत्नीभ्यः २. २, ५.
गन्धर्वम् २. २, ४; १४. २, ३६.
गन्धर्वस्य ४. ३७, ७; ७. ७७, ३; १४. २, ३५.
गन्धर्वाः ४. ३७, १२.
गन्धर्वाः ८. ५, १३; ७, २३; ९. १२, १०; ११. ७, २; १२. १, २३; ५०; १३. १, २३; १४. २, ९.
गन्धर्वाणाम् ३. २४, ६.
गन्धर्वान् ४. ३७, २; ८; ९; ८. ६, १९.
गन्धर्वाय १४. २, ४.
गन्धर्वीः १८. १, १९.
गन्धर्वेभिः ७. ११४, ५.
गन्धर्वैः ४. ३४, ३; १०. १०, १३.
गन्धार्य ११. २, ६.
गन्धारिऽभ्यः ५. २२, १४.
गन्धेन ४. ३७, २; ८. ६, १०; १२. ८, ७.
गन्वहि २०. ९२, ४.
गभस्तौ २०. ९४, २.
गभस्त्योः २०. ३०, ३.
गभिऽसक् ७. ८, १.
गभीरः ५. ११, ३.
गमः २०. ५०, २; ५२, २; ५३, २; ५७, १२; १५.
गमत् २०. ६९, १; ७८, ३.
गमत् २०. २६, २; ५३, ३; ५७, १३; ११३, १.
गमन् २०. ९४, ५.
गमन्तु १८. ३, ४५.
गमय १. २१, २; ३. ३, ६; ६. ८१, २; १२. ३, ३४.
गमयति ९. ५, २४.
गमयन् १८. ४, ६४.
गमयन्ति ९. ७, ६.
गमयाम् १८. २, २७.
गमयामः १६. ६, ४.
गमयामसि ३. १८, ३.
गमातः १०. ७, ४२.
गमाथ ३. ८, ४; १४. १, ३२.
गमाम १. ५, ३.
गमिष्ठः ५. २०, १२.
गमिष्यति ५. २२, ९; १०. ९, ११.
गमेत् २. ३६, १; ३. १२, ३; १३, ५; ६. ४, २.
गमेमहि १. १, ४; ७. १०, ४.
गम्भीरः १९. ४९, २.
गम्भीरम् १९. ५०, ३.
गम्भीरात् ५. ३०, ११.
गम्भीरे १९. २, ३.
गम्भीरे इति ४. २६, ३; ११. ७, ८.
गम्भीरैः १८. ४, ६२; ६३.
गयम् ७. ४३, १; ८९, १; २०. ६६, १.
गयस्य १. १४, ४; ६. ३, ३; २०. ३७, १.
गये २. ६, ३.
गरऽगीर्णः ५. १८, १३.
गरत् १६. ७, ४.
गरुत्मान् ४. ६, ३; ९. १५, २८.
गर्गरः २०. ९२, ६.
गर्गराः ४. १५, १२.
गर्गराणाम् ९. ४, ४.
गर्तऽसर्दम् १८. १, ४०.
गर्दभऽनादिनः ८. ६, १०.
गर्दभम् २०. ७४, ५.
गर्दभीऽइव १०. १, १४.
गर्दभे ५. ३१, ३.

गर्भ १९. ५७, ३.
गर्भऽअदम् २. २५, ३.
गर्भः ३. २३, २; ५; ५. २५, ७^{३}; ९; ६. १७, १; २; ३; ४; ९५, ३^{३}; १२१, ४; १२५, ३; ८. ७, ८; ९. १, ५; २१; १४, ९; १५, २३; ११. ६, २०; ७, ७; १३. १, ४; १९. ४४, ५.
गर्भःऽइव ९. ३, २१; ११. ९, ६.
गर्भऽकरणम् ५. २५, ६.
गर्भऽत्वम् २०. ४०, ३; ६९, १२.
गर्भऽधिम् २०. ४५, १.
गर्भम् १. ११, २; ३३, १; २; ३; ३. १०, १२; ४. २, ६; ८; ५. २५, २^{२}; ३^{३}; ४^{४}; ५; ७; ८; ६. १७, १; ७. २, १; ४०, १; ८. ६, १८; २०; ९. १५, १२; ११. ७, ३; १३. १, १६; २०. १६, ७; ९६, ११; १२.
गर्भम्ऽइव ११. ६, २६.
गर्भऽरसा ९. १४, ८.
गर्भस्य ५. २५, १.
गर्भाः ५. १७, ७.
गर्भात् १०. १०, २३.
गर्भान् ८. ६, २३; २५; ११. ६, ३.
गर्भाय ६. ८१, २.
गर्भे १०. ८, १३; २८; ११. ६, १४; १३. ३, २०; १८. १, ५.
गलुन्तः ६. ८३, ३.
गवाम् २. २६, ४; ५; ४. ९, २; २२, ४; ८. ३, १६; ४, १०; ७, १५; ९. ४, १७; १४, ३; १२. १, ५; १९. ३१, ८; ४७, ६; २०. ५६, ४; ८७, ६; ११८, २.
गवाम्ऽइव ३. ९, २.
गवि २. ३२, १.
गविष्ठिरम् ४. २९, ५.
गवीनिके इति १. ११, ५; ९. १३, ७.
गवीन्योः १. ३, ६; ५. २५, १०; ११; १२; १३.
गवे २०. ७८, १.
गव्यता २०. ८३, २.
गव्यन् ५. २०, ३; १०.
गव्यन्तः २०. ९६, ५; १२१, २; १२५, ३.
गव्यन्ता २०. ७२, २; ७५, १.
गव्यम् २. १३, १; ७. ८७, १; २०. १४, ४; ६२, ४.
गव्यस्य २०. ७२, २; ७५, १.
गव्यानि १९. ४९, ३.
गव्याम् १८. ३, २२.
गव्यूतिः १६. ३, ६; १८. १, ५०.
गहि ६. ७, १; १०८, १; १८. १, ५९; १९. ४, ३; २०. ६, ८; ९; २०, ४^{२}; २४, १; २; ३६, ११; ५७, २; ३; ७^{२}; ६८, २; ३; ७०, ५; ९७, २; १२०, २.
गह्वरम् १२. २, ५३.
गाः ३. २८, १; ७. १२०, ४; १२. १, ३९; १३. १, २; १९; १८. १, ६; २०. ८, १; १६, ३; ४; ५; १०; ११; २५, ५; २८, २; ३४, ३; ३५, १०; ३९, ३; ९१, ३; ४; ६; ८; ९६, ३; १३७, ११.
गाः ५. १९, ९; ३०, १^{२}; ६; ८. १, ७; १०; २, १; १२. २, १०.
गात् ५. १, ६; ३०, १४; ७. ५५, ४; ८. १, ७; १८; ९. १४, ४; १२. २, २३; ३, ४६; १६. ४, ३.
गात ७. ६२, ७.
गातम् ३. ११, ६.
गाताम् १२. ३, १४.

गातुः ७. ३, १; १०. ९, १; १३. २, ४४.
गातुम् २. ३४, २; ७. १०२, ७^{२}; १०. २, १२; १३. १, ४; १८. १, ५०; २०. ३६, ५.
गातुऽया २०. ४६, ३.
गातुऽवित् ११. १, १५.
गातुऽविदः ७. १०२, ७.
गातुऽविदम् १३. २, ४३.
गात्रा १०. ७, २७; ११. १, ३१; १८. ३, ९; २०. ४, २.
गात्राणि ५. २९, १२; ११. १, २४; १८. ४, ५२.
गात्राय १. १२, ४.
गाथया १४. १, ७; २०. १००, ३.
गाथाः १०. १०, २०; १५. ६, ११.
गाथानाम् १५. ६, १२.
गाथाभिः २०. १०३, १.
गाथिनः २०. ३८, ४; ४७, ४; ७०, ७.
गाधम् १९. ११, ६; २०. ३५, ११.
गाम् १. १६, ४; ३. ११, ८; १७, ३; ४. ९, ७; ५. १८, १; २; १०; १९, १०; २९, १; ६. २८, १; २; ७१, १; ७. ५२, ९; ८. ७, ११; ९, १५; ९. १४, ९; १०. १, १७; २९; १२. ४, २; १२; ९, ८; १३. १, ५६; २०. ११, ९; २७, ३; ५५, ३; ८५, २; ८९, २; ९१, ५; ९८, २.
गाम् ५. ३, ४.
गाम १३. १, ५९.
गाय ६. १, १^{२}; २०. ७८, १.
गायत २०. ६१, ४; ६२, ५; ८; ६८, १०; ११; ६९, २.
गायतः ४. १५, ३.
गायति ९. १०, २; ५; ७; ८.

गायत्रऽछन्दाः ६. ४८, १.
गायत्रम् ९. १५, १.
गायत्रस्य ९. १५, ३.
गायत्री ८. ९, २०; ११, ५; १८. २, ६; १९. २१, १.
गायत्रीम् ३. ३, २; ८. ९, १४; १०. ८, ४१; १३. १, १०.
गायत्रे ९. १५, १.
गायत्रेण ९. १५, २.
गायत्र्याः ४. ३५, ६.
गायत्र्याम् १३. ३, २०.
गायन्ति १२. १, ४१.
गायन्तु ४. १५, ४.
गार्दभम् ६. ७२, ३.
गार्हऽपत्यः ६. १२०, १; १२१, २; ७. ६६, २; ९. ७, १३; १२. २, ४४; १५. ६, १४; १८. ४, ८; ९; १९. ३१, २.
गार्हऽपत्यम् १४. २, १८; २०.
गार्हऽपत्यस्य १५. ६, १५.
गार्हऽपत्यात् १२. २, ३४.
गार्हऽपत्याय १४. १, २१; ५०.
गार्हऽपत्ये ५. ३१, ५; ८. १०, २; १०. १, १८.
गार्हऽपत्येन १२. २, ९.
गावः १. २, ३; ४, ३; ४; २२, ३; २. २६, ४; ४. २१, १; ४; ५^{४}; २४, २; ६. ९, ३; ५२, २; ७. ६२, ५; ८७, ६; १०१, १; ८. ७, २५; ९. ४, २०; १४, ५; ११. २, ९; ३, ५; १०, ३२; १४. १, १३; १९. ६, १२; ९, ८; ११, १; ५८, ३; २०. १२, ४; २२, ६; ३४, ७; ९२, ३; १४२, ४.

गावः ३. १४, ४; ६; ४. २१, ६; १४. १, ३२; ३३.
गावौं ७. १००, २; १४. १, ११.
गाष्ठांम्ऽइव २. १४, ६.
गाहमानः १९. १३, ७.
गाहेथाम् १२. ३, ३६.
गिरः २. ५, ४; २०. ६, ८; १०, १; १५, ४; २१, १; २४, ३; ३०, १; ३५, ४; ५९, १; ६३, ५; ६९, ६; ७०, २; ५; ७१, १०; ७६, ३; ५; ७८, २; ९६, २; १०४, १; ११०, १; ३; ११५, २.
गिरः १. १५, २; १९. १, १; २.
गिरति ५. १८, ७.
गिरयः ६. १२, ३; १२. १, ११; २०. ३५, १४.
गिरा २०. २२, ४; ४७, ३; ९२, १; ११; १३७, १४.
गिरामः ६. १३५, ३.
गिरामि ६. १३५, ३.
गिरामि ६. १३५, ३.
गिरिः ४. ६, ८; २०. ५१, ४; ६४, १.
गिरिऽभ्रजः २०. १६, १.
गिरिम् २. २५, ४; २०. ९, २; ४९, ५.
गिरिषु ५. ४, १; ९. १, १८.
गिरिऽस्थाः ७. २७, २; ८९, ३.
गिरीणाम् १०. ४, १४.
गिरीन् ६. १७, ३; २०. ६१, ५; ६२, ९; ९४, ८.
गिरेः ५. १३, ९.
गिरेःऽइव २०. ५१, २.
गिरौ ५. ४, २; ६. ६९, १.
गिर्वणः २०. ६, ६.
गिर्वणः २०. १५, ४; २३, ४; ६९, ५; ८; ८३, २; १००, १.
गिर्वाहः २०. ४५, २.
गिर्वाहसम् २०. १४३, १.
गिर्वाहसे २०. ३५, ४.
गीः २०. ३६, ५.
गीःऽभिः ३. २०, ४; ७. ११५, ३; १३. १, ५३; ५४; १९. ७, १; २०. ८, १; ९, १; १९, ३; ३६, १; ४४, १; ४९, ४; ५५, १; ६१, ४; ६२, ८; ७१, १५.
गुः ५. १, ४.
गुः ५. ८, ३; १८. १, ३२; ३, ६२; १९. १५, २.
गुणेभिः १०. ८, ४३.
गुदाः ९. ४, १४; १२, १६; १३, १७; १०. ९, १६; ११. ३, १०.
गुदाभ्यः २. ३३, ४; २०. ९६, २०.
गुपितः २. २८, ४; १४. १, ५.
गुपितम् ५. १७, ३.
गुपिताः १०. १०, ४; १८. ४, ७०.
गुप्तः ५. २०, १२; ११. १२, ११; १७. १, २९[२].
गुप्तये ६. १२२, ३; १२. ३, ७.
गुप्ता ११. ११, २; १२. ५, ३.
गुरस्व ५. २०, ४.
गुरुः ६. ४२, २; ९. ३, २४.
गुरुऽभृत् १२. १, ४८.
गुल्गुलु २. ३६, ७.
गुल्गुलु १९. ३८, २.
गुल्गुलूः ४. ३७, ३.
गुल्गुलोः १९. ३८, १.
गुल्फौ १०. २, १; २.
गुष्पितम् ३. ७, २; ७. ९५, १.
गुहा १. ८, ४; १३, ३; २. १, १; २[२]; ६. ९२, २; ८. ९, २; ९. १५, २७; १०.

८, ६; ११. ७, १०; ९, १५; १२. १, ४४; ४६; ६०; १४. १, १६; २०. १६, ७; २८, २; ३४, ४; ३९, ३; ७०, १; ९१, ४.
गुह्य॑ः १०. ७, ४१.
गुह्य॑म् ३. ५, ३.
गुह्य॑स्य ७. ३०, १.
गुह्या॑ ७. ३०, २.
गुह्या॑ः ११. १०, २८.
गूढः ६. १३४, २.
गूर्त॑ऽश्रवसम् २०. ३५, ५.
गूल्हे॑ इति॑ २०. १३७, १०.
गृहथाः ४. २०, ५.
गूह॑माना ८. ४, १७.
गृणत॑ ५. २७, ९.
गृणत ५. २७, ९.
गृणते ४. २१, २; ५. ११, ११; ८. ३, ११.
गृणत्ति १०. ७, ४३.
गृणन्त २०. ९९, १.
गृणन्त॑ः ६. ६२, २; २०. ३३, ३; ५०, १; ७१, १५; ७७, ३.
गृणन्ति २०. ११, ७.
गृणन्तु १८. १, ५२.
गृणाति २०. १०६, ३.
गृणानः १७. १, १०; २०. २५, ७; ३३, २; ७७, १; ८.
गृणाना १. १३, ४; ५. २७, ९.
गृणीत २०. ५०, १.
गृणीमसि ४. ३१, ५; २०. २१, २; ६१, १; ७३, ६.
गृणे २०. ९२, १६; १०५, ४.
गृणे २०. १०४, २.
गृत्स्य॑ः १९. ३४, २.
गृध्रः ११. २, २१.
गृधत् ८. ६, १.
गृध्यैः॑ १२. २, ३८.
गृध्र॑ः ५. २३, ४.
गृध्र॑ऽयातुम् ८. ४, २२.
गृध्रा॑ः ११. ११, ९; १२, ८; २४; १२. १०, १.
गृध्रे॑भ्यः ११. २, २.
गृध्रौ॑ ७. १००, १.
गृभाय २०. ४, २.
गृभाय २. ३०, ४; ३. १०, ६; ६. १२५, ३; ११. १, १४; १९. ४२, ३; २०. ५६, ४; ९४, ४.
गृभायत॑ ८. ४, १८.
गृभायत २०. ९२, ७.
गृभि॑ः १२. १, ५७.
गृभीतः ९. १५, १६.
गृभीत्वा १२. ३, २०.
गृभ्णामि ३. ८, ६; ६. ९४, २.
गृष्टिः ८. ९, २४.
गृष्टीनाम् २. १३, ३; १९. २४, ५.
गृहः २. १४, ३; ५. ६, ४; ११; ७. ८८, १.
गृहऽप॑तिः ८. १०, ३; १४. १, ५१; १९. ५५, ३; ४.
गृहऽप॑तिम् १९. ३१, १३.
गृहऽप॑त्नी १४. १, २०; २, ७५.
गृहऽप॑त्न्याः ३. २४, ६.
गृहम् ४. १८, २; २१, ६; ६. २७, २; २९, २; ३७, १; ११. १०, १८; १२. २, ७; १९. ४५, १; २०. ९२, ४; १२६, २२.
गृहऽमेधी ८. १०, ३; १९. ३१, १३.
गृहऽराजस्य॑ ११. १, २९.
गृहस्य॑ २. १४, ४.
गृहा॑ः ७. ६२, ४; ६.

गृहाः ६. १०६, २; ७. ६२, २; १२. २, ३९; ४, ३.
गृहाण ३. २, ५; ११. १, १०.
गृहाण ५. २९, १४.
गृहाणाम् ३. १२, ६; ६. ३२, १; ९. ८, १; २; ३; ४; ५; ६; १४. २, २६.
गृहात् ११. १०, १; १४. २, १९.
गृहान् १. २७, ४; ३. १०, ११; १२, ९; ७. ६२, १; ३; ९. ३, २३; ११, ५; १४. १, २०; २, २६; ७५; १५. १०, १; ११, १; १२, २; १३, ११; १८. २, २१; ४, ३७; ६३; २०. १२६, २०.
गृहासः १८. ३, ५१.
गृहीत्वा १९. ५८, ३[२].
गृहे १. १४, २; ३. २४, २; ३०, ४; ६. ५, ३; २९, ३; ७. ८१, १; ८. १२, ८; १०. १, २०; ६, ४; ८, २६; १२. ४, २७; ४८; १४. १, २१; २, ५९; ६०; ६१; १५. १३, १; ३; ५; ७; ९; १९. ३१, ३; ४५, २; ५७, ४; २०. ४१, ३.
गृहेभ्यः २. १४, २; ६. १३७, १; १४. २, १७; २७; १८. २, २७.
गृहेषु ६. ४५, १; ७९, १; २; ७. ६२, ५; १४. २, ६२; १८. ३, १७.
गृहैः ७. ८६, ४; ५; १४. २, १२.
गृह्णते १८. ३, १८.
गृह्णन्तः १९. ३५, १.
गृह्णन्तु २. ३४, ५; ९. ५, ३७.
गृह्णाति ६. ७६, ४; १३. ३, ११.
गृह्णातु ११. १, ११.
गृह्णातु ३. १७, ४; २९, ८; ५. १४, १२; ११. १, ८; १८; १४. १, ४९.
गृह्णानः ५. २०, ४; ६. ८१, १.
गृह्णानाः ५. १७, १०.
गृह्णानाम् ४. ३८, २.
गृह्णामि ५. १३, २; १२. ३, १७; १४. १, ५०.
गृह्णामि ३. २९, ७; ६. ८२, १; ७. ८७, २; ९. ३, १५[२]; १२. २, ३३; १४. १, ४८; १९. ३७, २.
गृह्णाहि ३. १०, १३; ५. २९, १५.
गृह्णीतम् ११. ११, ११.
गृह्णीतात् ११. १, १३.
गृह्णीयात् १०. १०, २; २७.
गृह्णे १९. ३१, ४.
गृह्याः ५. २०, ४.
गेष्म ४. ११, ६; १४, ६; ११. १, ३७.
गोऽअग्रया २०. २१, ५.
गोऽअजम् १९. ५०, ५.
गोऽआशिरम् २०. २४, १; ७.
गोऽइषे २०. ६५; २.
गोऽइष्टौ ४. २४, ५; २०. १४३, ९.
गोऽएषणः ५. २०, ११.
गोऽएषणम् २०. १२, ३.
गोः १. २२, १; ७. ५, ५; २३, २; १२. २, ३७; १८. १, ३२; २०. २१, २; ३२, १; ३५, १२; ४१, ३; १४३, १.
गोऽजाताः १९. ११, ४.
गोऽजित् ५. ३, ११; ७. ५२, ८.
गोऽजितम् ६. ९७, ३; १७. १, १; २; ३; ४; ५; १९. १३, ६.
गोऽजिति १३. १, ३७.
गोतम १८. ३, १६.
गोतमम् ४. २९, ६.
गोतमासः २०. ३५, १६.
गोत्रस्य ५. २, ८; २०. १०७, ११.

गो॒त्रा २०. ७७, ८.
गो॒त्राणि॑ १९. १३, ७.
गो॒ऽदाः २०. ५७, २; ६८, २.
गो॒ऽदुहे॑ २०. ५७, १; ६८, १.
गो॒धा ४. ३, ६; २०. ९२, ६.
गोऽधा॑यसम् २०. ९१, ७.
गो॒ऽधुक् ७. ७७, ६; ७; ९. १५, ४.
गोऽप॑तये १२. ४, ३७; ३९.
गोऽप॑तिः ४. २१, ३; १२. ४, २७; १८. ३, ४; २०. २७, २; ८७, ६.
गोऽप॑तिना ३. १४, ६.
गोऽप॑तिम् १२. ४, ४; २२; ५२; १९. ५८, ३; २०. २२, ४; ९१, ८; ९२, १.
गो॒ऽप॒ते॒ ५. १८, १५.
गोऽप॑तेः ८. २, २३.
गोऽप॑तौ २. २६, ४; १२. ४, ८.
गोप॑नम् १२. ४, १०.
गोऽप॑रीणसा २०. २२, ३.
गो॒पा ५. ९, ८; १४. २, ५.
गो॒पाः ३. ८, ४; ५. ३, २; ६. ७७, २; ७. २७, ५; ५५, २; ८६, ६; ९. १४, २२; १०. ८, ९; १२. १, ५७; ३, ११; १६. २, ३; १८. २, ५४.
गो॒पाम् ९. १५, ११; १३. २, २.
गो॒पाय॑ १९. ४८, ४.
गो॒पा॒य॒त॒ १२. ३, ५५; ५६; ५७; ५८; ५९; ६०.
गो॒पा॒य॒तः॒ १५. ४, ३; ६; ९; १२; १५; १८.
गो॒पा॒यत॑म् ५. ९, ८.
गो॒पा॒य॒तु १९. १७, १; २; ३; ४; ५; ७; ८; ९; १०.
गो॒पा॒यन् ८. १, १३.
गो॒पा॒यन्ति॑ १८. २, १८.
गो॒पा॒य॒न्तु ८. १, १४; १९. १७, ६.
गो॒पी॒थः १६. २, ३.
गो॒पी॒थाय॑ ५. ९, ७.
गोऽपु॑रोगवम् ८. ७, १२.
गो॒ऽपो॒षम् १३. १, १२.
गो॒प्ता ११. १, ३३; १७. १, ३०.
गो॒प्तारः॑ १०. १०, ५.
गो॒प्तारौ॑ ५. ३०, १०; १५. ४, २; ५; ८; ११; १४; १७.
गो॒प्तृन् १९. २७, ४.
गो॒प्स्य॒न्ति॒ १०. ९, ७; ८; ९,
गोभिः॑ ३. १६, ३; ६. १०८, १; १२५, १; २; ७. ५२, ७; ८६, ४; ५; १०२, २; १०. ६, २३; १८. २, ५८; १९. २७, १; २०. १६, २; १२; १७, १०; २१, ४; ३८, ६; ४७, ६; ७०, ९; ८९, १०; ९४, १०.
गोभ्यः॑ १. ३१, ४; ३. २८, ३; ६. २७, ३; ५९, ३; ९. ३, १३; १२. २, १६; १९. ४७, ९.
गोऽम॑त् १८. ३, ६१; २०. ७, ३; १२, ६; ७१, १३; ८९, ७.
गोऽम॑तः ३. १०, ११; २०. ६०, ३; ७८, २; ९०, ३.
गोम॑ताम्ऽइव ४. ३६, ६.
गोऽम॑ति २०. ८१, २; ९२, २१.
गोऽम॑ती ३. १२, २; २०. ६०, ४; ७१, ४.
गोऽम॑तीः ३. १६, ७.
गोऽम॑न्तम् २०. ९, २; २५, ४; ४९, ५; ५२, ३; ५७, १६; ७७, ६; ७८, ३.
गोऽमा॑न् ६. ६८, ३.
गोऽरू॑पम् १९. ४९, ८.
गो॒ऽरू॒पम् ९. १२, २५.

गोऽवपुषः २०. १६, ९.
गोऽविर्दन् १९. १३, ५.
गोषु ३. १५, ७; २१, २; ४. १८, ५; २२, २; ६. ३८, २; ४५, १; ५५, २; ६९, १; ९. १, १८; ४, ११; १०. १, ४; ११. २, २१; १२. १, ४; १९; २, १; १५; ४, २७; २८; ३९; १४. १, ३५; २,५३; ५४; ५५; ५६; ५७; ५८; १९. ४५, २; ५७, ४; २०. २५, १; ७४, १; २; ३; ४; ५; ६; ७.
गोऽसखा २०. २७, १.
गोऽसनिम् ३. २०, १०.
गोऽसेधाम् १. १८, ४.
गोऽस्थः ३. १४, ५; ६; ११. १, १३.
गोऽस्थम् २. २६, २; ६. ५९, २; ७. ७९, २; १२. २, ४.
गोऽस्थात् २. १४, २.
गोऽस्थे २. २६, १; ३. १४, ३; ४. २१, १; ६. ५२, २; ७. ४०, १; ९. ४, १९; २३; १३. १, १९; १९. ३१, १.
गोस्थेऽइव ११. १०, ३२.
गोऽस्थेन ३. १४, १.
गौः ५. १८, ३; ११; ६. ३१, १; ६७, ३; ८. २, २५; ९, २५; २६; ९. १४, १७; १५, ६; ७; २१; १२. ४, ३९; ७, ६; १३. १, ४१; २०. ४८, ४.
गौःऽइव ३. १८, ६; ६. ४९, १; ८. ६, १७.
गौरः २०. २२, ३.
गौरात् २०. ८७, १.
गौर्यः २०. १०९, १.
ग्नाः ७. ५१, २; २०. ३५, ८.
ग्नाभिः १९. १०, ६.
ग्मन् २०. ७६, ५.
ग्रन्थिः ९. ३, २.
ग्रन्थीन् ९. ३, ३.
ग्रभीता १. १२, २.
ग्रसते १९. ३४, ८.
ग्रहाः ११. ९, १८; १९. ९, ७; १०.
ग्राभम् १४. १, ३८.
ग्रामऽघोषी ५. २०, ९.
ग्रामऽजितम् ६. ९७, ३; १९. १३, ६.
ग्रामऽनीः १९. ३१, १२[२].
ग्रामऽन्यः ३. ५, ७.
ग्रामम् ४. ३६, ७; ८; ५. १७, ४.
ग्रामम्ऽइव ४. ७, ५.
ग्रामाः १२. १, ५६; २०. ३४, ७.
ग्रामात् १८. २, २७.
ग्रामान् ५. २०, ३.
ग्रामाय ६. ४०, २.
ग्रामे ४. २२, २; ८. ७, ११.
ग्राम्याः २. ३४, ४; ३. १०, ६; ३१, ३; ११. ७, २१; १९. ६, १४.
ग्रावऽभिः २०. २४, २.
ग्रावऽभ्याम् ६. १३८, २.
ग्रावा ५. २०, १०; २२, १; ६. ३, २; १०. ९, २; १२. ३, १४; २१; २०. २५, ६.
ग्रावाणः ३. १०, ५; ४. २४, ३; ८. ४, १७; ९. ६, १५; १९. १०, ७.
ग्रावाणौ ११. १, ९; १०.
ग्राव्णाम् १४. १, ५.
ग्राहिः ३. ११, १; ६. ११३, १; ३; २०. ९६, ६.
ग्राहिम् ८. २, १२; १२. ३, १८.
ग्राह्यः ५. १७, ३.
ग्राह्या ३. २, ५; १२. २, ३९; १६. ७, १.

ग्राह्याः २. ९, १; १०, ६; ८; ६. ११२, १; २; १६. ५, १; ८, ३; १९. ४५, ५.
ग्रीवाः ६. ३२, २; १३४, १; ९. १२, ३; १०. १, २१; २, ४; ९, २०; ११. १०, १५; १९. ४९, ९.
ग्रीवाभ्यः २. ३३, २; २०. ९६, १८.
ग्रीवासु ६. ६३, १.
ग्रीष्मः ६. ५५, २; १२. १, ३६; १५. ३, ४; १९. ६, १०.
ग्रीष्माय ८. २, २२.
ग्रैव्याः ६. २५, २; ७. ८०, २.
ग्रैष्मम् ५. २२, १३.
ग्रैष्मौ १५. ४, ५; ६.
ग्लपयन्त ९. १४, १०.
ग्लहनम् ७. ११४, ५.
ग्लहा ६. २२, ३.
ग्लहात् ४. ३८, ३.
ग्लहे ४. ३८, १; २.
ग्लौः ६. ८३, ३.

घ

घ ५. १३, १०; ११; ६. १, ३; १८. १, ३; ११; ४, ८८; २०. ७, १; १७, २; १८, २; २१, ७; २६, २; ५२, १; ५७, १४; ६९, १; ७८, २; ९२, १४; १११, १; १२२, २.
घनः २०. ६८, ८.
घना २०. ७०, १९.
घनाघनः १९. १३, २.
घनेन १०. ४, ९.
घर्मः ४. ११, ३; ७. ७७, १; २; ५; ७; ८. ८, १७; ९. १२, ३; १५, ४; ११. ३, १८; २०. १३९, ४.
घर्मःऽइव १९. २८, २; ३.
घर्मदुघे इवेति घर्मदुघेऽइव ४. २२, ४.
घर्मम् ४. १, २; ११, ५; ६. ३६, १; ७. ७७, ४; १०२, ४; ९. १५, ६; ११. ७, ५; १२. १, ७; २०. १४०, २.
घर्मसत्ऽभिः १८. ३, ४७; ४८.
घर्मस्य ४. ११, ६.
घर्मऽस्वेदेभिः २०. ९१, ७.
घर्माः ८. ९, १३.
घर्मान् ९. १, ८.
घर्मे ७. ७७, ६.
घसत् २०. १२६, १३.
घातुकः १२. ४, ७.
घारय १२. ३, ३७.
घासः ४. ३८, ७; ८. ७, ८.
घासम् ११. ७, १८; १८. २, २६; १९. ५५, १; ६.
घासात् १८. २, २६.
घृणिः ७. ३, १.
घृतऽआहुतः १३. १, १२; २८.
घृतऽआहुतम् ४. २३, ३.
घृतऽकेशम् २०. १०३, ३.
घृतऽपदी ७. २८, १.
घृतऽपावा १३. १, २४.
घृतऽपृष्ठः २. १३, १; ९. १४, १; १२. ३, १९; ५३.
घृतऽपृष्ठाः ९. ५, १५; १८. ४, ५.
घृतऽप्रतीकः २. १३, १.
घृतऽप्रियम् १२. १, २०; १८. ४, ४१.
घृतऽप्वः ६. ५१, २.
घृतम् २. १३, १; ३. १२, १; १३, ५; १६, ७; ७. १९, २; २७, ३; ३०, १; २; ७७, ४; ८७, ६[3]; ११४, २; ८. ७, १२; ९. २, ११; ४, ४; ७; १०. ६, ५; ९, ११;

१०, ३२; ११. ७, १५; १२. १, २९; १८. १, ३२; २, १४; २०. ३०, १.
घृतऽयोने ७. २७, ३.
घृतऽवत् ३. १०, ६; १७, ९; ७. ७०, २; ९. २, ८; १२. ३, ४५; १८. २, ३.
घृतऽवता ३. १०, ११.
घृतऽवती ३. १२, २.
घृतऽवतीः १९. ४२, २.
घृतऽवन्तः ४. ३५, ५; २०. ७६, ६.
घृतऽवान् १८. ४, १९.
घृतऽवृद्धः १३. १, २८.
घृतऽश्चुतः १. ३३, ४; १०. ९, २७; १८. ३, ५१; ६८; ४, २५; ४२.
घृतऽश्चुतम् १०. ६, ६; ७; ८; ९; १०; २०. ११९, २.
घृतस्य ३. १२, ८; ६. ९, ३; ७. ३०, १; २; ८७, १; ९. ४, ५; १०. ६, २५; १८. ३, ७२; ४, ५७; १९. ५८, १; २०. ६७, ३.
घृतऽस्तावः १२. २, १७.
घृतस्नू इति घृतऽस्नू २०. २३, ९.
घृतस्नू इति घृतऽस्नू १८. १, ३१.
घृतऽह्रदाः ४. ३४, ६.
घृता ५. २७, ४.
घृताची ९. १, ४; १०. ४, २४; १९. ४८, ६.
घृताचीम् १३. १, २७.
घृतात् ५. २८, १४; १९. ३३, २; ४६, ६; २०. ६५, २.
घृतेन १. ३१, ३; ३. १२, ४; १५, २; ३; १७, ९; ४. १४, ६; २६, ६; २७, ५; ५. १२, १०; २७, २; २८, ३; ६. ५, १; २२, १; ३२, १; ५१, २; ७३, २; ९३, २; ७. ५९, १; ७९, २; ८७, ६; १०३, १; ११४, १; ३; ४; ९. २, १; १५, २२; ११. १, १८; ३१; १२. ३, ३७; ४१; ४४; १३. १, ८; ३३; १८. ३, १०; १९. २७, ५.
घोरऽचक्षसे ८. ४, २.
घोरम् १. १८, ३; ६. १४०, ३; १६. १, ८; १८. ४, ८३; १९. ९, ३; ४; ५; १४; २०. ३४, ५.
घोरस्य ७. ७३, ५.
घोरा ५. १८, १५.
घोराः २. ३५, ४.
घोराणि १२. ७, २.
घोरात् ४. ९, ६; १८. ४, ९.
घोरे ६. ८४, १.
घोरैः १६. ७, २.
घोषः ३. १३, ६; १९, ६; ५. २०, ७; १९. १३, १०; २०. १२, २.
घोषऽबुद्धा ५. २०, ५.
घोषम् ३. १०, ५; ४. ३१, ४; ७. ४४, १; ८. ६, ११.
घोषाः ३. १९, ६; ७. ५४, २; ११. ११, ११; २०. १६, १.
घोषात् २०. ६७, २.
घोषिणः ४. १५, ४.
घोषिणीः ११. ९, २०.
घोषिणीभ्यः ११. २, ३१.
घ्नताम् १. २८, ४.
घ्नते १९. ३२, २.
घ्नन् ५. २३, ६; २०. ९०, २.
घ्नन्तः ७. ९८, १; ८. ८, १३.
घ्नन्तम् २०. ११, ११.
घ्नन्ति ६. ७६, ४; ८. ५, १३; १०. ८, २४.

म्रन्तु **३.** १, ६; **७.** ७३, २; **८.** ४, १७; ८, २०.

म्रंसः **१३.** १, ४८; ५३.

म्रंसम् **१३.** १, ४६; ४७; ५२.

म्रन् **७.** १९, २.

च

च **१.** २, ४[४]; ५, ३; ६, २; ३; ७, ३; ८, ३; ९, १; १०, ४; ११, ५[२]; १२, ३[२]; १३, ३; १४, ४; १५, ४[२]; १७, २; १९, २; ४; २०, ३[२]; २२, १; २३, १[२]; २[२]; ४; २९, ६; ३०, २; ४; ३२, ३; ४[२]; ३५, ३; **२.** २, ३[२]; ४, ५[२]; ६, २[३]; ७, २[२]; ९, २; १०, ६; १३, ३[२]; १४, ३; ४; १५, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; २५, ३[२]; ३०, २[२]; ३४, ३; ३५, ४; ५; **३.** १, १; ३; २, १; ३, ६; ५, ७; ६, १; २; ३; ५; ६; ९, ४; १०, ७[२]; १५, ४[२]; १७, ३; २०, ४; ५; ६; ७; ८[२]; ९; २२, २[३]; ४; २३, ३; ४; २४, ५; ७[२]; २८, ५; ६; ३०, ४; **४.** १, १[२]; ४; ७; २, ४; ५; ३, ३[२]; ४, ८; ५, २[२]; ५; ९, ९[२]; ११, ९[२]; १०; १६, २; ८; १८, ७; २०, २; ४; ७; ९; २१, २; ३[२]; २२, ६; २३, ७; २५, १; ३; ४[२]; ७; २८, ४; ३१, ७; ३२, ३; ३३, २; ३; ३६, १; २; ३७, १०; ३८, ४; **५.** २, २[२]; ६; ९[२]; ३, ७; ४, ९[२]; ५, २; ६, १[२]; ९; १०; ७, ३; ८; ८, ७; ११, ११; १२, १; २; ३; १३, ६; ७[४]; ९; १५, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १७, ३; ७; ८; १८, ९; २१, २; ७; २३, १[२]; ४[३]; ५; ६[३]; ७[२]; १३[२]; २५, ४[२]; २७, ६[२]; २८, २; १४; २९, १४; ३०, ४; ५; ९; १०[२]; १६; १७; ३१, ९; **६.** २, १[२]; ५, १; ३; ६, ३; १४, १; १५, २[२]; १६, ३[२]; १९, ३; २२, २[२]; २३, १; २४, २; २५, १[२]; २[२]; ३[२]; ३१, १; ३४, ४; ३५, ३; ३७, ३; ४०, १; ४२, ३; ४३, १[२]; ४४, २; ४९, २[३]; ५०, ३; ५१, ३[२]; ५३, १[३]; ५४, ३[२]; ५७, ३[३]; ६१, २; ६६, २; ६७, १; ७१, १; ७२, ३; ८१, १; ८५, २; ८७, ३; ८८, २[२]; ९०, १; ९४, ३[२]; ९६, ३; ९८, १; १०१, १; १०२, १[२]; ३; १०४, १; ३; १०७, १[२]; २[२]; ३[२]; ४[२]; ११०, १[४]; ११२, ३; ११५, २; ११७, ३; १२०, ३; १२१, २[२]; १२२, २; १२४, २; १३३, ४; १३६, ३; १३८, ३; १३९, ३[२]; १४०, १; २; ३; **७.** ४, १[५]; १०, १[२]; १३, १[२]; २; १४, १[२]; २१, १; २; ६; २६, २[२]; ३४, १[२]; ४५, १; ५८, ८[२]; ६१, १; ६९, १; ७३, १[२]; ३; ८०, ३; ४; ८४, २; ८६, ३[२]; ८७, ५; ९४, ३[४]; ९५, ३; ११४, २; ३; ५; ११५, १; **८.** १, ९[२]; १२[२]; १३[६]; २०; २, २०[२]; ३, ३; ४, १०; ११[२]; १२[२]; २५; ५, ९; १०; १६; १८[२]; २२; ६, ४[२]; ७; १०; १५; २३; २४[२]; ७, १; ५; १०; १३; १७; १८[४]; २०; २४; ८, ९[३]; १७[२]; १८; ९, ७; ११, ६[४]; १३, ११[२]; १२[२]; १५[२]; १६[२]; १९, २; **९.** १, १७; २२[६]; २, ३; १५[३]; ३, २; ४; ५; ९; १२[२]; १५[२]; २२; ४, २२[२]; २४; ५, ६; १४; १९; २१[२]; २७; ३७[२]; ७, ६[२]; ८, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ११, ३[२]; १२, १[२]; ७[४]; ९[२]; १०[२]; १३, १७; १८; २२; १४, १३; १९; २१; १५, ११[२]; **१०.** १, १३; २१; २२; ३२; २, ९; १२[२]; १९[२];

२४; २५; २६; २९^{२}; ३, ८; १२^{३}; १४^{२};
१६; १८; ४, ३^{२}; ८^{२}; ९; १०; १५;
१६^{२}; १७; ५, २२; २३; ७, ८; १०^{४};
११^{२}; १५^{२}; १७; २२^{५}; ३३; ३८; ८, १^{४};
२^{३}; ४; १०^{२}; ११^{२}; १२; १६; १७; ३४^{२};
९, ६; ७; ९; १२^{२}; १३; १४; १६; १७;
१८; १९; २०; २१; २२; २३; २६; १०,
३; २१; ३०; ३१; **११.** १, ६; ३३;
३४; २, २; ३; १६^{२}; २९; ३१; ३, २४^{२};
२८; २९; ४, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{२};
७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; १२^{२}; १३^{२};
१४^{२}; १५^{२}; १६^{२}; १७^{२}; १८^{२}; ५, ६; ७;
६, ४; १०^{२}; १५; १७; १८; ७, १; ५;
८; ९; २१^{२}; २३; ८, ६; ९; १२; ९, १^{३};
३^{३}; ५; ९^{३}; ११^{२}; १२^{२}; १५; १७^{२}; २०^{२};
२२; २३^{२}; २५^{२}; २६; २७; १०, २^{२}; ४^{२};
६^{२}; १५; २०^{२}; २१^{५}; २२^{५}; २३^{३}; २४;
२५^{३}; २६^{२}; २७^{३}; २८^{३}; ३०; ११, १^{३};
४^{२}; ७; १३; १५; १६; १७; १८^{२}; २२^{५};
२३^{२}; २४; २५^{२}; १२, २; ७; ९; ११^{३};
१८; २२^{३}; २३; २४; **१२.** १, ५; १२;
२३; ३१; ४७; ५०; ५१; ५२; ५३^{४}; २,
२^{३}; १४; १८; १९; ३६^{२}; ४०^{२}; ३, ५^{२};
६; ९; १२; २५^{२}; २७; २९; ३४; ३६;
४६; ५०; ४, १; २; ७; १२; १३; १४;
१६; १८; १९; २१; २५; २६; २८^{२};
३८^{२}; ४४; ४८; ५३; ६, १^{८}; २^{८}; ३^{८};
४^{३}; ७, २; ८, ११^{२}; १०, १०; **१३.** १,
८; १२^{२}; १३; १९; २५; ३४^{६}; ३७;
३८; ४६; ४७; ५४; ५५; ५६^{२}; ५७^{२};
५८^{३}; २, ५^{२}; १४^{२}; ३५; ४, ११^{२}; ५,
१^{७}; ६^{२}; ६, १^{३}; २^{६}; **१४.** १, ३३; ३५^{२};
३९; ४५; ४८^{२}; ५३; २, ४^{२}; ९; २०;

२२; २९; ३४; ३५; ३७; ४१; ४२^{२};
४६; ५१; ५९; ६०; ६१; ६२; ६६; ६९;
७४; **१५.** २, २^{४}; ३^{४}; ४^{४}; ६^{२}; ७^{२}; ८^{२};
१०^{५}; ११^{५}; १२^{५}; १४^{६}; १६^{४}; १७^{४};
१८^{४}; २०^{६}; २२^{४}; २३^{४}; २४^{४}; २६^{२};
२७^{२}; २८^{२}; ३, ४^{४}; ५^{४}; ४, २^{२}; ३^{२}; ५^{२};
६^{२}; ८^{२}; ९^{२}; ११^{२}; १२^{२}; १४^{२}; १५^{२};
१७^{२}; १८^{२}; ६, २^{६}; ३^{६}; ५^{५}; ६^{५}; ८^{४}; ९^{४};
११^{४}; १२^{४}; १४^{६}; १५^{६}; १७^{७}; १८^{७};
२०^{४}; २१^{४}; २२^{२}; २३^{३}; २५^{४}; २६^{४}; ७,
२^{६}; ४^{५}; ८, ३^{४}; ९, २^{४}; ३^{४}; १०, ३^{२};
१२, ३^{२}; १३, १२; १७, ८; ९^{२}; १८,
४^{२}; **१६.** २, ५^{२}; ३, २^{४}; ३^{४}; ४^{४}; ४, ६;
६, ४; **१७.** १, ६^{२}; ७^{२}; २१^{२}; २४; २७;
२८; २९^{२}; **१८.** १, ४; १५; १९; २६;
२८; ४५^{२}; ४७^{२}; ५४; ५५; २, २; ७^{२};
१२; ३४; ३७; ५६; ५८; ३, १; १४^{२};
१९; ३८^{२}; ४४; ५५; ७२; ४, २८^{२}; २९;
५७^{३}; ६२^{२}; ७५; ७६; **१९.** ६, ३; ४; ७^{२};
११; १२^{२}; १४; ७, २; ३; ५; ८, २^{२}; ५;
९, २^{२}; ८; १०; १९, १^{२}; २^{२}; ३^{२}; ४^{२};
५^{२}; ६^{२}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; २०,
२; २४, ५^{२}; ६; २५, १; २६, ३^{२}; २७,
१०; ३१, ३; ४^{२}; ५; ७^{२}; १०^{२}; ११;
१३; १४; ३२, ७; ८^{४}; ९; ३३, २; ३४,
२; ३६, ३; ३७, १; ३९, १; ५; ६; ७;
८; १०; ४०, १; ४१, १; ४२, २; ४४,
१०^{२}; ४५, २^{२}; ४; ४६, १^{२}; ३; ६^{४}; ४७,
४^{४}; ५^{२}; ४८, १^{२}; ३^{३}; ५; ४९, ५; ५३,
५; ५४, ३; ५^{५}; ५५, ५; ५७, ४; ५८,
५; ६; ६३, १; ६४, १^{२}; २^{२}; ६८, १^{२};
२०. ६, ८; ९; ७, २; ११, ८; १३, १;
४; १५, ५; १७, १२; १८, ५; ६; १९,

१; ७; २०, ६; २४, ७; २८, ३; ३५, ४; १४[२]; ३६, ८; ३७, ४; ५[२]; १०[२]; ३९, ४; ४४, २; ४६, ३[३]; ४८, ४; ५४, १; ५५, १; २; ५७, ९; ६०, ६; ६१, २; ६; ६२, १०; ६३, १[५]; ६५, २; ६७, २[२]; ५; ७०, १०; ७१, १; ६; ७६, ५; ७; ८३, १[२]; ८५, १; ३; ८७, ७; ९१, ३; ९२, ४; ९६, १०; १०६, २; १०७, ५[२]; ९; १२[२]; १४; ११२, १; ११३, १; ११५, ३; ११६, २; १२४, ४[५]; १२६, २०[२].

चकमानार्य **१९.** ५२, ३.

चकर्त **२०.** ९१, ६.

चकर्तिथ **२०.** १५, ६.

चकर्थ **२०.** ७५, ३.

चकर्थ **६.** १००, ३; **२०.** ८७, ३.

चकर्श **१२.** ३, १६.

चकानः **२.** ५, १.

चकार **२.** ५, ५; ९, ५; **३.** २४, २; **४.** १८, ६[२]; **५.** ८, ७; १४, ६; ९; ३१, ११[२]; **७.** ११४, ५; **९.** १५, ७; १०; **१०.** १, २८; ८, २६; **१३.** १, ५२; **१९.** २०, २; **२०.** ८७, ५; ९०, २; ९२, १८; १२६, ३.

चकार **४.** ६, १; **६.** ६५, ३; **९.** ३, ३; **१८.** २, २७; **२०.** ११, ७; १६, १०; ७७, ४.

चक्रम **६.** ११४, १; ११५, १; ११८, १; **७.** १११, १; **१०.** ३, ८; **१२.** २, ४०; **१८.** १, ४.

चक्रम **१८.** १, ३३; ५१.

चक्रऽवान् **२.** ३५, ३.

चक्रषे **१८.** २, २०.

चक्रथुः **३.** १७, ७; **९.** १४, १९.

चक्रम् **९.** १४, २; १३; १४; **१०.** ८, ४; **११.** ९, ४; **१३.** ३, १८; **१४.** १, १४; १६.

चक्रमे **७.** २७, ४; ५; **१०.** ८, ४१; **१३.** २, २७[२]; ३, २५.

चक्रये **२०.** ७१, ८.

चक्रवाकाऽइव **१४.** २, ६४.

चक्रा **१८.** १, ८; ९; **१९.** ५३, १.

चक्राणः **२०.** २७, ५.

चक्रान् **१९.** ५३, २.

चक्राम **२०.** १४, २; ६२, २.

चक्रिम् **२०.** ७१, ८.

चक्रिरे **४.** ७, ७; **५.** ६, २; ८, ६; **११.** १२, १७; **१८.** २, १६.

चक्रुः **४.** १७, ४[३]; १८, ५; **५.** ३१, १[३]; २[२]; ३[२]; ४[२]; ५[२]; ६[३]; ७[३]; ८; ९; **६.** ११६, १; १४१, ३; **१०.** १, ४; **१४.** २, ६५; **१९.** ३५, १; २.

चक्रुः **१०.** ७, ४४; **११.** ११, २५; **२०.** ७७, ३.

चक्रुर्षम् **४.** १३, १.

चक्रुर्षे **४.** १८, ४.

चक्रे ४, १७, १; **५.** ८, ८; **९.** १४, ११; **१०.** ७, ३२; ३३; ३४; ३६; **१२.** १, १०; **१९.** २०, ३.

चक्रे **१.** २४, १; २; **२.** २७, ३; **८.** ९, २; **९.** ३, ११; **१२.** ३, ५४; **१३.** १, ११; ३, २५; **१९.** ६, १४; **२०.** १६, ५.

चक्रे इति **१४.** १, ११; १२; १६.

चक्रेर्ण **२०.** २१, ९.

चक्र्योः **२०.** १२२, २.

चक्लृपत् **६.** ३५, ३.

चक्लृपुः **९.** १५, १९.

चक्लृपे **७.** ९२, १.

चक्लृपे ६. ३६, २.
चक्षणम् ५. ४, ३; २८, ७; ६. ९५, १; १९. ३९, ६; ७; ८.
चक्षणी इति १०. २, ६.
चक्षते ९. १५, २६; १८. ४, २९.
चक्षसा १३. २, २१; २०. ४७, १८; ९४, ३; ८७, ६.
चक्षसे १. ५, १; ६. १९, ३; ३९, १; ४१, १; ६८, २; ७६, १; १०. ६, ८; २०. ३८, ६; ४७, ६; ७०, ९.
चक्षुः २. १७, ६^{2}; ३५, ४; ५; ३. २२, ५; ४. ५, ४; १४, ५; २०, ७; ५. ९, ७; १०, ८; १३, ४; २१, १०; ३०, १३; ६. ५३, २; ७. २७, ७; ८. १, २०; २, ३; ३, २१; ९. १४, १४; १०. २, २९; ३०; ६, ३५; ७, १८; ३३; ३४; १०, २४; ११. ३, ३; ७, २५; ९, २५; १०, ४; २६; ३१; १२. १, ३३; ३, २; ६, ३; १३. १, ४५; २, ३५; १४. १, ६; १६. २, ५; १८. १, १०; २, ४६; १९. ३५, ३; ४३, ३; ४४, ५; ४६, ३; ५१, १; ५३, ६; ५८, १; ५; ६०, १; २०. १९, २; ९६, १०; १०७, १४.
चक्षुःऽमन्त्रस्य २. ७, ५; १९. ४५, १.
चक्षुषः ४. ९, ६; ५. ६, ९; ९. २, २; १२. ३, ३२.
चक्षुषा १. ३३, ४; २. १६, ३; ३४, ३; ५. ६, १०; १३, ४; २१, २; ३०, १४; ६. ९६, ३; ७. ६२, १; ८. ३, ९; ७, १८; ९. ४, १७; १०. ७, ३९; ८, १४; १०, १५; ११. ९, २३; १३. ३, ६; १४. २, १२; १६. १, १२; १८. २, ७.
चक्षुषाम् ५. २४, ९.
चक्षुषी इति ९. ५, २१.
चक्षुषे ५. ४, ७; ६. १०, ३; ८. २, ४; ३, ८; १४. २, ३५; १८. ३, १०.
चक्षुष्मती १९. ४९, ८.
चक्षुष्मते १२. २, २१.
चक्षूंषि ३. १, ६; ११. २, ५.
चक्षे ५. ११, २.
चक्षोः १९. ६, ७.
चक्ष्व ५. २०, ४; ८. ४, २५^{2}; २०. ९६, २४.
चचर्त १४. १, ५६.
चचार ९. ५, ३.
चण्डस्य २. १४, १.
चतस्रः १. ११, २^{2}; २. ६, १; १०, ३; ४; ३. २२, ५; २४, ६; ५. ३, १; १५, ४; ६. ४०, २; ८. ५, ३; ८, २२; ९. २, ११; १५, १९; १०. ७, १६; ११. २, १०; ७, १२; १२. १, ४; ५५; १३. ३, ६; १७. १, १६; १९. १, ३; १०, ८; ३३, ५.
चतुः ११. २, ९.
चतुःऽअक्षम् २. ३२, २.
चतुःऽअक्षात् ८. ६, २२.
चतुःऽअक्षी ५. १९, ७.
चतुःऽअक्षौ १२. २, ११; १८. २, १२.
चतुःऽअक्ष्याः ४. २०, ७.
चतुःऽउत्तराणि ८. ९, १९.
चतुःऽऋचेभ्यः १९. २३, १.
चतुःऽदंष्ट्रान् ११. ११, १७.
चतुःऽधा ४. ३४, ७; ८. ९, २४; ११, १; १०. १०, २९.
चतुःऽपक्षा ९. ३, २१.
चतुःऽपदः ३. २१, २; ४. २, १; २८, १;

२; ३; ४; ५; ६; **६.** २८, ३; **११.** २, १; **१२.** १, १५; **१३.** १, २; ३, २४.
चतु॑ःऽपदा **९.** १५, २; **१९.** १५, २.
चतु॑ःऽपदाम् **२.** ३४, १; **८.** २, ४; २३; **१९.** ३१, ५.
चतु॑ःऽपदी **९.** १५, २१; **१०.** १, २४; **११.** १२, ६; **१३.** १, ४२.
चतु॑ःऽपदीम् **१८.** ३, ४०.
चतु॑ःऽपदे **६.** २७, १; ५९, १; **११.** २, २८; **१४.** २, ४०.
चतु॑ःऽपात् **४.** ११, ५; **६.** १०७, १; २; ३; ४; **८.** ८, १४; **१०.** ८, २१; **१३.** ३, २५; **१९.** ३१, ४; ३४, १.
चतु॑ःऽपादः **१०.** २, ६.
चतु॑ःऽबिलम् **१८.** ४, ३०.
च॒तुःऽभि॑ः **३.** ७, २; **४.** १४, ९.
चतु॑ःऽभृष्टिम् **१०.** ५, ५०.
च॒तुःऽभ्य॑ः **१.** १२, ४; ३१, १; **१९.** ४५, ५.
च॒तु॒ःऽरा॒त्रः **११.** ९, ११.
चतु॑ःऽवीरम् **१९.** ४५, ३; ४; ५.
च॒तु॒ःऽवृ॒षः **५.** १६, ४.
चतु॑ःऽश्रोत्रा **५.** १९, ७.
चतु॑ःऽहनुः **५.** १९, ७.
चतु॑ःऽहोतारः **११.** ९, १९.
च॒तुर॑ः **४.** १५, १४; ३४, ७; **८.** ९, २४; **१४.** १, ६०; **१९.** २७, ३.
च॒तु॒र्थः **१३.** ५, ३; **१५.** १५, ६; १६, ४; १७, ४.
च॒तु॒र्थम् **८.** ९, ३.
च॒तु॒र्थीम् **१५.** १३, ७.
च॒तु॒र्द॒श॒ऽऋ॒चेभ्य॑ः **१९.** २३, ११.
चतुष्टयम् **१०.** २, ३.
चतु॑ष्पक्षम्ऽइव **३.** ७, ३.
च॒त्तः **९.** ५, ९.
च॒त्वार॑ः **१.** ३१, २; **१९.** ४७, ४.
च॒त्वारि॑ **८.** २, २१; **९.** १५, २७; **१४.** १, ६०.
च॒त्वा॒रि॒ंशत् **५.** १५, ४; **१९.** ४७, ४.
च॒त्वा॒रि॒ंश्याम् **२०.** ३४, ११.
च॒न **१.** २०, ४; **३.** १९, ८; **४.** ५, २; २५, २; २६, ६; २८, ५; ३४, ३; **५.** ३, ४; १९, १०; **६.** ५७, ३; १२७, १; १३०, ३; **७.** ८, १; १०, ३; ३८, १; ३९, ४; ४५, १; **८.** ४, ३; ८, ६; १९; **९.** २, १०; २४; ११, ४; **१०.** ५, २३; ७, ३७; ८, १६; ४४; **११.** ६, २१; २५; ११, १३; २०; १२, १९; **१२.** १, १८; २३; २४; २५; **१८.** १, ४८; २, २४; ३२; **२०.** ५९, ४; ८२, २; ९३, २; १२६, ११.
चन॑ः **२०.** ८४, ३.
च॒नि॒स्क॒द॒त् **२०.** ९२, ६.
चन्द्र॑ **२.** २२, १; २; ३; ४; ५.
च॒न्द्रः **२.** १५, ३; **३.** ३१, ६; **४.** ३९, ८; **१५.** ६, ५; **१९.** २७, २; ४३, ४[२].
च॒न्द्रम् **१.** ३, ४; **१२.** २, ५३; **१३.** ३, १०; **१४.** २, १०; **१९.** २६, २.
च॒न्द्र॒म॒ः **७.** ८६, २; **१४.** १, २४.
च॒न्द्रम॑सः **२०.** ४१, ३.
च॒न्द्रम॑सा **१३.** ६, ७.
च॒न्द्रम॑सि **१०.** ३, १८; **११.** ७, १३.
च॒न्द्रमा॑ः **५.** २४, १०; २८, २; **६.** ८३, १; ८६, २; **८.** १, १२; ८, २३; **९.** २, २४; **१०.** ६, १०; ७, २; १२; ३३; **११.** ६, १२; ८, ७; ९, २; १२, १६; **१५.** १५,

५; १८, २; १८. ४, ८९; १९. ६, ७; ८, १; १९, ४.
चन्द्रस्य १५. ६, ६; १९. २७, ९.
चन्द्रार्य ४. ३९, ७²; १९. ४३, ४.
चन्द्रासः २०. ६, ४.
चन्द्रे १९. २७, १०.
चन्द्रेण ४. ३९, ८.
चमसऽअध्वर्यवः ९. ११, ३.
चमसः ७. ७७, ३; ८. १४, २; १०. ८, ९; १६. ३, ३; १८. ३, ५३; १९. ४९, ८; ५८, ४.
चमसम् ६. ४७, ३; १८. ३, ५३; ५४; २०. १६, ८.
चमसे २०. ३१, ४.
चमसेन ७. ११९, ३.
चमू इति २०. ४२, ३.
चमूऽसदः २०. १७, ४.
चम्वोः ९. १९, १२.
चयत् ७. ५२, ३.
चयनेन १८. ४, ३७.
चर २. ११, ३; ३. २, ३; ४. १७, ८; ६. ४९, १; १३९, २; ४; ८. १, १२; १८. ४, ३१; २०. ७३, ३; ९६, २४.
चरणीनाम् २०. ६६, २.
चरणे ७. १११, १.
चरण्यात् ७. ३०, १; २.
चरत् १३. २, ४०.
चरत ६. ६७, २; ९. ४, २४.
चरतः ७. ५९, १; ११३, २; ८. २, ११.
चरतः ७. ८६, १; ८. ९, १२; ११. २, १४; १३. २, ११; १४. १, २३; १८. १, ३५; २, १३.
चरति ४. ५, ५; १६, २²; ७. २१, ६; १८. २, १०; १९. ५६, ४.
चरति ३. १०, ४; ४. ८, १; ३; १०, ७; ११, २; ३; ३९, ९; ५. १७, ५; १८, १३; ६. ३१, २; ७. १०, १; ८. ९, ११; २२; ९. १, ४; १५, ८; १०. ८, १२; १३; ११. २, १२; ६, २०; ७, १; २३; १२. ४, ३७; २०. ४८, ५.
चरतु ७. ७७, ५; ९. २, १४.
चरते १२. १, ३१.
चरथ ३. ९, ४.
चरथम् २०. ५३, २; ५७, १२.
चरध्यै २०. ३५, १२.
चरन् ४. ५, २; १६, १.
चरन्तः ३. ३०, ५.
चरन्तम् ३. ३, ४; ४. २९, ७; ५. १८, ५; ७. ७५, २; ८. ३, ५; ४, ८; ९. १५, ११; २०. २६, ४; ४७, १०; ६९, ९; १३७, ८.
चरन्ति ४. २७, ४; ६. ५१, ३; ११. १२, ८; १२. १, ४९; १८. १, ९; २, २८; १९. ६६, १; २०. १०३, ३.
चरन्ति ४. १६, ४; २१, ४; ११. ७, १३; १२. १, १५; २, ४१.
चरन्ती १२. ४, २९; ३९.
चरन्तीम् १४. १, ५६.
चरमऽअजाम् ५. १८, ११.
चरमतः १९. १५, ३.
चरसि ३. ६, ४.
चरसि १३. १, ४०; २०. ५३, २; ५७, १२.
चरसै १३. २, ६.
चराचरः १४. १, ११.
चरातै ३. ४, ३.

चरामः ६. १३३, १.
चरामसि ६. ४५, ३; २०. १५, ४; ११८, १.
चरामि ३. १५, ५; ६; ६. ११७, १.
चरामि ४. ३०, १; ९. १५, १९.
चरितम् ३. १५, ४; ९. १, ३.
चरित्राणि १०. २, १२.
चरुः ८. ४, २; ११. १, १६; १८; १८. ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.
चरुम् ११. १, १७; ३, १८; २०. ७०, १२; १२६, १८.
चरुम्ऽइव ४. ७, ४.
चरूणाम् १८. ४, ५३.
चरेत् १२. ४, १६; २७.
चरेते इति ८. ९, १२.
चरेम ३. १२, १; १२. १, १७; १९. ५८, ३[२]; २०. १४३, ८.
चरेयम् १७. १, २७.
चरोः ९. ५, ६.
चर्किरन् २०. ५७, ३.
चर्कृत्यः ६. ९८, १.
चर्कृत्यम् २०. ६६, २.
चर्म ४. १२, ४; ९. १२, १५; १०. ९, २; १७; २४; ११. १, ८; १२. ३, १; १४; १४. २, २२; २४.
चर्मऽइव २०. १०७, २.
चर्मणा ४. १२, ४; ५. १८, ३.
चर्मणि १०. ९, २६; ११. १, ९; १४. २, २३.
चर्षणिऽधृतः २०. १९, ४.
चर्षणिऽप्रः ४. २४, ३.
चर्षणिऽप्राः २०. ११, ७; ७३, ३.
चर्षणिऽसहम् २०. १४, ४; ६२, ४; ८०, २; ८५, २.
चर्षणीनाम् १. ५, ४; ७. ८९, २; १३. १, ३८; १९. ५, १; १३, २; २०. ३६, १; ४४, १; ७०, १५; ९२, १६; १०५, ४.
चष्टे ७. २६, २.
चष्टे ४. ११, २; १६, ५; ९. १, ५; १०. ८, ३०.
चस्कन्द १८. ४, २८.
चस्कभाने इति ४. २, ३.
चाकन् २०. ७६, १.
चाकशीति ९. १४, २०.
चाक्षुष १६. ७, ७.
चातयत् १९. ४४, ७.
चातयन् १९. ३४, ९.
चातयामहे २. १४, २; ४. ३७, २.
चातुःऽमास्यानि ११. ९, १९.
चान्द्रमसाः १९. ९, १०.
चायित्वा ९. १, १.
चारु २. १३, १; ७. १३, १; १२. १, ५६; १४. १, ३१; १९. ७, २; २०. ३०, १; ३५, ७; ८७, २.
चारुः २. ५, १; ३६, ४; १३. १, ३८; १८. ३, ७; १९. २४, ६; ३३, ३; २०. ११७, २.
चारुम् २०. ९६, ३.
चिकिताम् ६. ५३, १.
चिकितुषः ९. १४, ७.
चिकितुषी ४. ३०, २; ७. ४९, २.
चिकितुषे ८. ४, १२; १४. २, ४१; २०. ७७, २.
चिकिते २०. १२, २.
चिकित्वन् ७. १०२, १.

चिकित्वा ७. ९४, २.
चिकित्वान् ५. १२, १; १३. २, ३२; ४२; १८. १, ३०; २, ३७.
चिकित्सति १३. २, १९.
चिकित्सतु ६. ६८, २.
चिकित्सतु ६. १४१, १; १०. ६, ९.
चिकित्सर्वः १०. १, १.
चिकित्सात् ९. २, ३.
चिकीर्षति ५. ८, ३; १२. ४, १९.
चिकीहि १. १०, ४.
चिकेत ५. १, २; ७. २, १; ५, ९.
चिकेत ९. १, ६; ७; १४, १५; १९, २३; १०. २, २; ७; ८, ४; २०. १८, २; १४०, २.
चिकेतथः २०. १३९, ४.
चिकेतसि २०. ७२, ३.
चिक्युः ९. १५, १६; १०. २, ४.
चिक्युः ९. १५, १६.
चिक्षिपः १८. २, ४.
चिक्षिपन् १८. ४, १२; १३.
चित् ३. ३, २; १६, २[३]; ४. ६, ४; २१, ५; ६[२]; २८, २; ५. २, ४; ८; ११, ४; ६; २७, ४; ३०, ११; ६. ३, ३; २०, १; ९७, २; ७. १५, ४; १७, १; १९, २; ४३, १; ९७, १; १११, १; १२२, १; ८. ४, ७; ९. १४, ७; १५, २३; १२. ४, ७[२]; १४. २, ४७; १८. १, १[२]; ३; ८; २०; ३३; ५२; २, १४; १५; १६; १७; ३, २३[२]; ६५; १९. ५, १; ९, १३; ६४, ३; २०. १२, ४; १४, १; १७, १२; २१, १; ३१, ५[२]; ३४, ८; १४[२]; १८; ३५, ६; ८; ३६, ४; ६; ३७, ९; ४५, १; ५६, २; ६०, २; ५; ६१, ३; ६२, १; ६३, ६; ६८, ५; ७०, १[२]; ७१, ५; ७३, २; ५; ७४, १; ७७, ३; ५; ६; ८५, १; ३; ८७, ७; ८९, ६; ९०, २; ९१, ११; ९२, १४; ९५, २; ९७, २; १००, २; १०७, ३; ७; ११; १२४, २; १२५, २; ७.
चितम् १८. ४, १४; ३७.
चितयन्तः २०. ७२, १.
चिते ७. २३, २.
चित्तऽआकूतम् ११. ११, १; १३.
चित्तम् १. ३४, २; ३. १, ४; ८, ६; १९, ५; २५, ५; ५. ३, २; ७, ८; ६. ९, २; ४२, ३; ४३, ३; ६४, २; ९४, २; १०. १०, १८.
चित्तये ६. ४१, १.
चित्तस्य १९. ४, २.
चित्तात् ५. १८, ९.
चित्तानि १. ९, ४; २. ३०, २; ३. २, १; २; ३; ४; ५; २५, ६; ५. २१, ४; ५; ६; ७. ८२, २; ११. १०, २७.
चित्तिः १४. १, ६.
चित्तिनः ३. ३०, ५.
चित्तिऽभिः ९. १५, ७.
चित्तेन ३. ६, ८.
चित्तेभिः ३. ८, ६; ६. ९४, २.
चित्त्या ५. ६, १०.
चित्त्याम् ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
चित्यम् १०. २, ८.
चित्र २०. ८०, १; ९८, २.
चित्रः १३. २, ३२; ४२; २०. १२४, १.
चित्रऽभानु १३. ३, १०.

चित्रभानो इति चित्रऽभानो ४. २९, ३; २०. ८४, १.
चित्रम् १३. २, ३४; ३९; २०. १४, १; ६२, १; ६७, २; ७१, ११; १०७, १३; १४.
चित्रया २०. ९७, २.
चित्रऽरथः ८. १४, ६.
चित्रऽराधाः १. २६, २.
चित्रा १९. ७, ३; १३, १.
चित्राणि १९. ७, १.
चित्राभिः २०. ८१, २; ९२, २१.
चित्वा १०. २, ८.
चिनोति ७. ९२, ६; २०. १७, ५; ८९, ९.
चिनोतु ८. ३, ४; ११. १, २४.
चीक्लृपाति २०. ६३, १; १२४, ४.
चीतिम् २. ९, ४[२].
चीपुद्रुः ६. १२७, २.
चुच्यवत् २०. २०, ५; ५७, ८.
चुच्यवीरत २०. १४०, ३.
चुर्मुरिम् २०. ३७, ४.
चृत ६. ६३, २; ८४, ३; ११२, १; २.
चृततु ५. २८, १२.
चृतामसि ५. २८, १२; ९. ३, १; ३; ४; ५; ६; ८; १३; १४.
चृतामि ९. ३, १८.
चेकिते २०. २१, ३.
चेतः ६. ६४, २; ९. १२, ११.
चेतत् ९. १४, १९.
चेतति २०. ६३, ७.
चेततु ३. २२, २.
चेतनम् २०. ११०, ३.
चेतनीम् ९. ४, २१.
चेतयन्ती ५. १२, ८.
चेतयेथाम् २०. १४०, ५.
चेतसः ६. ११६, ३.
चेतसि ११. १२, २.
चेतसे ६. ४१, १.
चेत्ता ४. ८, २.
चेत्तारम् ५. ३, १०; ६. ९९, १.
चेत्तुः ६. ७३, १.
चेरिम ७. ६७, २.
चेष्टतः ११. ६, २३; २४.
चोदत् १९. ५, १.
चोदय ३. २०, ५; ७; २०. ७१, ११; १२.
चोदयत २०. १३७, २.
चोदयन् २०. ५८, २.
चोदयन्ताम् १९. ७१, १.
चोदयस्व ७. ४८, ३.
चोदयामि ५. २, ५; २०. १०७, ८.
चोदयामि ३. १५, १.
चोदयासे २०. ७६, ८.
चोदामि २०. २४, ८.
चोदिता २०. ३४, ६; ९५, २.
च्यवना २०. ३४, ४.
च्यवनाय ७. १२१, १.
च्यवय १०. ४, २५; २०. ८९, २; १३७, २.
च्यवयति १०. १, १३; २०. ३७, १.
च्यवयतु १८. २, ५४.
च्यवयन् १२. १, ५१.
च्यवयन्तु ३. ३, २; १२. ३, ३५.
च्यवयिष्णुः १९. ३३, २.
च्यवस्व १८. ३, ९.
च्यवेथाम् १८. ४, ४९.
च्युता ९. २, १५.
च्योष्ठाः ६. ८७, २.
च्यौत्नानि २०. ३७, ५.

छ

छदिः ३. ७, ३; १४. १, १०.
छन्दः ८. १३, १४; १२. ३, १०; १४. १, ८; १९. ६, १३.
छन्दःपक्षे इति छन्दःऽपक्षे ८. ९, १२.
छन्दःऽभिः ६. १२४, १.
छन्दसा ११. ९, ८.
छन्दांसि ४. ३४, १; ५. २६, ५; ८. ९, १७; १९; ११. ९, २४; १८. १, १७; २, ६.
छर्दिः २०. ८३, १; १०३, १; १३९, १; १४१, ५.
छर्दिःऽपौ २०. १४१, १.
छादयसि ९. ३, १४.
छादयामि ७. १२३, १.
छायकात् ८. ६, २१.
छायया ५. २१, ८.
छाया ४. २, २.
छायाम् ५. १९, ९; १३. १, ५६; ५७.
छायाम्ऽइव ८. ६, ८.
छित्थाः ८. १, ४.
छिद्यते ९. १४, ११.
छिद्रम् १९. ४०, १.
छिनत्ति १२. २, ३७; ९, ५.
छिनत्ति १२. ८, ११.
छिनत्तु ५. २९, १०.
छिनद्मि ६. १४, २.
छिनद्मि ७. ७८, २.
छिनन्तु ४. १६, ६.
छिन्तम् ६. ५०, १.
छिन्द्धि १९. २८, ६[४].
छिन्द्धि १०. ३, १६.
छिन्धि १२. १०, ५.
छिन्धि ४. १९, १; ७. ११८, १; १२. १०, ५[२]; ११, ७.
छिन्नम् ४. १२, ५.
छिन्नस्य ४. १२, १.
छिन्ना ३. ६, ७; ९. २, १२.
छुबुकात् २. ३३, १; २०. ९६, १७.
छ्य ९. ५, ४.

ज

जक्षिऽवांसः ७. १०२, ३.
जक्षिऽवान् ४. ७, ३.
जगत् ५. १७, ७; ६. १७, ४; ४४, १; ७७, १; ८८, १; १२६, १; ९. १५, १.
जगतः ४. २, २; ७. १८, १; ९. ३, १७; १२. १, ६; १३. २, ३५; १९. ५, १; २०. ३६, ९; १०७, १४; १२१, १.
जगता ३. १२, ७; ९. १५, ३.
जगताम्ऽइव ८. ५, ११; १९. ३९, ४.
जगति ९. १५, १.
जगत्ऽइव ६. १२, १.
जगती ८. ९, २०.
जगतीम् ८. ९, १४.
जगते १. ३१, ४.
जगत्ऽछन्दाः ६. ४८, २.
जगत्ऽपौ २०. १४१, १.
जगत्यै १९. २१, १.
जगन्वान् १८. १, १.
जगम्यात् ७. २७, २; ४२, १; ८९, ३; २०. ३५, १६.
जगाम ७. ७५, २; १८. ४, ५४; १९. ४०, १.
जगाम ७. २१, ५.
जगार ९. १५, ९.
जगृहुः १०. १, ११.
जगृहे १८. १, ३३.

जग्धऽपाप्मा ९. ७, ८.
जग्धम् ५. २९, ५.
जग्ध्वा ५. १८, १०; १९, १०.
जग्मुः २०. १२५, २.
जग्मुः २. ५, ६.
जग्मे ९. १४, ८.
जग्मे २. २, ३.
जग्रभ २०. ११५, १.
जग्रभ १९. ३१, ५,
जग्रभम् ६. २१, १.
जग्राह २. ९, १; ३. ११, १; १८, ३; १४. १, ४८; २०. ९६, ६.
जग्राह १९. ५८, २.
जघनम् १४. १, ३६.
जघन्थ २०. १३७, ११.
जघन्याम् ७. ७८, २.
जघन्वान् २०. १२, ३.
जघस ६. ११७, २.
जघान २. ५, ३; ४. १२, ७; ८. ८, ७; १०. ४, १२; १८. २, ३१; २०. ३४, १०; ११; ४१, १; ७३, ६.
जघान ४. ३७, १; ७. १९, २; १०. ४, १८.
जघास ५. २९, २; ४.
जघ्निम १०. ४, १२.
जघ्नुः ४. ३७, १.
जङ्गिड १९. ३४, ८.
जङ्गिड १९. ३४, ३.
जङ्गिडः २. ४, २; ३; ५; ६; १९. ३४, १४; २; ४; ७; १०; ३५, २; ३; ४; ५.
जङ्गिडम् २. ४, १; १९. ३५, १.
जङ्गिडस्य १९. ३४, ५.
जङ्गिडेन २. ४, ४.
जङ्घनाव ४. ३२, ७.
जङ्घनीहि ५. २०, ८.
जङ्घयोः १९. ६०, २.
जङ्घाः ९. १२, १०; १०. ९, २३.
जङ्घाभिः ४. ११, १०.
जङ्घे इति १०. २, २.
जजनुः २०. ५४, १.
जजान ३. १०, १२; ६. ३८, १; २; ३; ४; १०. ८, ७; १३; ११. ६, २२; १३. १, १; ३, १; १५; १८. ४, ५४; २०. ३४, ३; ७.
जजान ६. ६१, ३; ७. ८४, ४; ८५, ३; १०. २, ३; १३. १, ६; १९. ३१, ११.
जजार १०. ८, २६.
जजास ५. १३, १.
जज्ञानः ५. २, १; २०. ८७, ३; १०१, ३; १०७, ४.
जज्ञानम् ४. १, १; ५. ६, १.
जज्ञानाः १८. १, ५०.
जज्ञिरे १०. ७, २९.
जज्ञिरे १०. १०, २१; ११. ९, ११; २३; २४; २५; २६; २७; १९. ६, १२; १३.
जज्ञिषे ४. १०, २; ५. ३०, १७; १९. ३१, ९.
जज्ञिषे १. ७, ६; ४. १०, ६; १०. १०, १९; १९. ५६, ५; २०. ९५, ३.
जज्ञे ४. १, ३; २४, ६; ५. २, १; ९. १, १; ३; १०; २०. १०७, ४.
जज्ञे ४. १, ६; ६, १; ७. ५, २; ८. ९, ५; ९. २, १९; १०. १०, २०; ११. १०, ६; ९; १३. १, ५५; १९. २२, २१; २३, ३०.
जठरम् २. ५, २; १३. ३, ४; २०. ३३, १.

जठरे॑ ११. १, २५; २०. ६, ५; ८, २; २४, ५; ३२, ३.
जत्रव॑ः ११. ३, १०.
जत्रुऽभ्य॑ः १४. २, ४७.
जत्वः ९. २, २२.
जनऽअय॑नाः १२. १, ४७.
जन॑ः १. ८, १; ३. २०, ६; ४. ५, ६; ५. ११, ४; ३०, २; १०. १, ८; २०. १, २.
जनता॑ः ५. १८, १२.
जन॑नात् ६. १०९, २.
जन॑म् ४. ५, ७; ५. ४, ८; ७, ८; ८, ७; २२, १२; ७. ८९, २; १२. १, ४५.
जन॑माने २०. ५८, १.
जन॑म्ऽइव ५. २२, १४.
जनय॑ ६. १३६, २; १३. १, १९.
जनय ३. १६, ३; २३, ३; ७. ११६, १; १४. २, २४; ३१.
जन॑यः ५. १२, ५; १२. २, ३१; १८. ३, ५७; २०. १७, १.
जनयत् १४. २, १४; २०. ९१, १.
जनयति ७. २०, १.
जनयतु १४. २, ४०.
जनय॑थ १. ५, ३.
जनय॑न् ७. ३, १; ११. ७, ७; २४; १३. १, ११; २, २६; २०. ११, ४.
जनय॑न्त ८. ३, १२; १०. ५, ४८.
जनय॑न्ति ३. २३, ४.
जनय॑न्तीः ४. २, ८.
जनया॑ः ३. २३, ३.
जनयावहै १४. २, ७१.
जनये॑ १४. १, ४६.
जनऽयोप॑नः १२. २, १५; २०. १२६, २२.
जनऽराज्ञः २०. २१, ९.
जन॑स्य १. २९, ६; १८. २, ३०; २०. ३६, ९.
जना॑ २०. ७२, २; ७५, १.
जना॑ः ५. १९, २; ६. ३३, १; ८४, १; ७. ६, १; ८. ५, ७; १०. ७, १०; २१; २५; २८; ९, ७; १४. २, ५९; २०. ८५, ३; ८९, ४.
जना॑त् ६. ८१, ३; ७. ४६, १.
जना॑न् ३. ५, ६; ७; ४. ५, १; ६. ६९, २; ७४, ३; ७५, ३; ७. ५९, १; ९. १, १९; १२. १, ५७; २, ९; १३. २, १८; २१; १४. २, १०; १८. २, १३; १९. २६, ३; ३२, ७; २०. ४७, १५; १८.
जना॑नाम् १. ३३, २; ४. १६, ५; २२, ५; ५. ५, २; ६. ९८, २; ७. २२, १; १२. १, ६१; १३. २, ४६; १८. १, ४०; ४९; ३, १३; २०. १७, ६; ३२, २; ५६, ६; ८५, ४; ९३, ३.
जनाय ४. ३०, ५; ८. ४, १२; २०. ३६, ८; ९०, २; १४३, ४.
जना॑सः ४. २५, ३; ५. ११, ७; ८; २०. ३४, ९.
जनासः १. ३२, १; ४. २१, ५; २०. ३४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १३; १४; १५.
जनि॑ऽकामः २. ३०, ५.
जनितव्य॑म् ४. २३, ७.
जनिता २. १, ३; ४. १, ७; ९. ४, ६; १५, १२; १३. १, १३; ३, १९; १८. १, ५; २०. १०५, १.
जनितार॑म् ४. १४, १; १०. ४, १८.
जनितुः ११. ९, १५; १६.
जनि॑तोः १९. ५६, २.

जनित्रम् १. २५, १; २; ६. ४६, २; १२०, २; ११. १, ११; १३. ३, २१; १४. २, ३४; १६. ५, १; ४; ५; ६; ७; ८.
जनित्राः २. २८, ३.
जनित्री ३. १०, ४; ८. ९, ११; १२. ३, ४.
जनित्री इति ५. १२, ९.
जनित्रीऽइव १२. ३, २३.
जनित्रीम् ६. ११०, ३; ९. ५, ३०; १८. ४, १.
जनिऽत्वम् ७. ६, १.
जनिऽत्वम् १८. ३, २.
जनिधाःऽइव २०. ७६, ५.
जनिम २. २८, २; ३१, ५; ४. १, ३; ५. ११, ५; ६. १२, १; १८. ३, २२; २३.
जनिमानि १. ८, ४; १३. १, ३७; ३, २१.
जनिऽयते ६. ८२, ३.
जनिऽयन्ति १४. २, ७२.
जनिषीय ९. १, १४.
जनिष्ट ४. १, ५.
जनिष्यते २०. १२१, २.
जनीःऽइव २०. ५, १.
जनीनाम् ७. ५१, २; १३. १, ४.
जनुषः ४. १, ५; ७. १२०, ३; २०. ३५, १४; ९७, ३.
जनुषा ९. ४, २४; १४. २, ३३; २०. ११४, १.
जनुषाम् १३. १, ४.
जनुषे ४. १, २.
जने ४. ३६, ९; ६. ५१, ३; १६. ४, ५; २०. १६, २.
जनेभ्यः २०. ३९, १; ७०, १६.
जनेषु ४. २८, ४; ६. ३३, ३; १८. ४, ३०; २०. १२, २; २०, २; ५७, ५.
जन्तवः २०. ५६, ६.
जन्तोः ८. ४, १६.
जन्म ६. ८०, ३.
जन्मना ५. २८, ६.
जन्मानि १३. २, २२; २०. ४७, १९.
जन्यम् १३. ७, १५.
जन्या २०. ८९, ६.
जन्याः ११. १०, १; २.
जन्युः १८. १, ३.
जभार ७. १००, ३.
जभार ४. १, ३; ५. ३१, १०[२]; १०. ७, ४३; ११. ७, ९; १२; २०. १६, ८; ९; १२३, १.
जभ्य ६. ५०, २.
जभ्रे २०. ३५, ८.
जमत्ऽअग्निः ६. १३७, १; १८. ३, १५.
जमत्ऽअग्निम् ४. २९, ३.
जमत्ऽअग्ने १८. ३, १६.
जमत्ऽअग्नेः ५. २८, ७.
जमदग्निऽवत् २. ३२, ३; ५. २३, १०.
जम्भः ८. १, १६.
जम्भनः १०. ४, १५.
जम्भय २०. ७४, ७.
जम्भयत् ४. ९, ९.
जम्भयताम् ५. २३, १.
जम्भयन्तम् ८. ६, १७.
जम्भयाः १९. ४७, ८.
जम्भयामसि २. ३१, २; ४; ४. ३, ३; ४; ५. २३, ३; ५; ६. ५०, ३.
जम्भात् २. ४, २.
जम्भिषत् २०. १२६, ४.
जम्भे ३. २७, १; २; ३; ४; ५; ६.
जम्भैः ८. ३, ३.

जयं ३. १९, ८; ८. ८, २४; ११. १२, १८.
जय ६. ९२, २; १२६, ३; ८. ८, २४[३]; ९. ५, ६; १२; २०. ६१, ३.
जयः ७. ५२, ८.
जयत् २०. १७, ५.
जयत ३. १९, ७.
जयत ११. १२, ९; १४; १९. १३, ३.
जयताम् ३. १९, ६; ११. ११, १८; १९. १३, १०.
जयति ७. ५२, ६; ९. १, २३; ११, १४; २०. ८९, ९.
जयतु ६. १२५, १.
जयन् ११. ११, १८; २०. ९०, २.
जयन्तम् ५. २, ४; ६. ९७, ३; ७. १२३, १; १९. १३, ६; २०. १०७, ७.
जयन्ताम् ८. ३, १६; ८, २४.
जयन्ति ४. २२, ५.
जयन्ती ५. ५, ३.
जयन्तीः ११. ११, १९.
जयन्तीनाम् १९. १३, ९.
जयन्तु ६. ६५, ३.
जयन्तु ५. २१, १२; ६. १२६, ३[२]; ८. ८, २४; १९. १३, ११.
जयम् २. २९, ३.
जयाति २. २७, १; ६. ९८, १.
जयातै ६. ९८, १.
जयेथे इति ७. ४५, १.
जयेम २०. ७०, १९.
जयेम ५. ३, १; ७. ५२, ४; ७; ९. ५, १८; १२. १, ४७; ३, १५; १३. १, २२; १८. २, ५९; २०. १७, १०; ८७, ४; ८९, १०; ९४, १०.
जरत् १०. ८, ६.
जरत्ऽअष्टिः २. २८, ५; ८. २, १; ५, १९; २१; १४. १, ५०; १७. १, २७.
जरत्ऽअष्टिम् ५. ३०, ५; ८; १२. १, २२; १४. १, ४९; १८. ३, १०; १२.
जरतीः १४. २, २९.
जरतीम् १२. २, ५४.
जरदष्टी इति जरत्ऽअष्टी ९. ३, ९.
जरन्ते २०. १८, १.
जरसः ५. ३०, १७; ६. १२२, १; ४; १०. २, ३०; ११. ५, ७.
जरसम् १. ३०, ३; २. १३, १; १२. २, २४.
जरसा ३. ३१, १; ८. २, ८; २०. १२६, ११.
जरसि २. १०, ५; १२. ३, ६; १८. २, ५१.
जरसे १. ३०, २; ३. ११, ६; ६. ५, २; ७. ५५, ४; १२. ३, ५५; ५६; ५७; ५८; ५९; ६०; १४. १, ४५; १८. ३, १०; १९. २४, २; ३; ३०, २; ३३, ४.
जरा ३. ११, ७; ११. १०, १९; १२. ३, ५५; ५६; ५७; ५८; ५९; ६०; १८. ४, ५०.
जराम् ८. २, ११; १९. २४, ५.
जरामहे २०. २३, ७.
जराऽमृत्युः १९. २४, ८; २६, १; ३०, १.
जराऽमृत्युम् २. १३, २; २८, २; ४; १९. २४, ४.
जराय ९. १४, १३.
जरायु १. ११, ४[२]; ५; ६; ६. ४९, १; ९. ४, ४.
जरायुऽजः १. १२, १.
जरायुणा १. ११, ५; ६; ६. १०६, ३.
जरायुऽभिः १. २७, १.
जरायै ३. ११, ७[२],

जरितः ५. ११, ८; २०. ८९, २.
जरितरिति २०. ८९, १.
जरितारः २०. १२, ४; ३६, ४.
जरितारम् २०. १४३, ७.
जरितुः २०. २१, ३.
जरितृऽभ्यः २०. ५१, १.
जरितृणाम् २०. १२२, ३; १२४, ३.
जरित्रे १८. १, ४०; २०. ११, ५; १२, ५; ८९, ७.
जरिमन् २. २८, १.
जरिमा ३. ११, ८.
जरिम्णः ७. ५५, ५; १८. ३, ६२.
जरिम्णे ८. ३, २०.
जर्हृषाणः १८. २, ५८.
जलाषः १९. १०, ६.
जलाषऽभेषज २. २७, ६.
जल्पिः १९. ५६, ४.
जवः ६. ९२, २; १९. ६०, २.
जवम् ४. २७, ३; ३६, ५; ६. ९२, १; १०. २, १५.
जवानि १९. ७, १.
जषाः ११. २, २५.
जसुम् २०. १६, ६.
जहरुः ३. ९, ६.
जहाति १०. १, ३२; १२. २, ११; २५.
जहाति १०. २, ३०; ८, ३२; ११. ५, ७.
जहातु ५. २९, १५.
जहातु ७. ३२, १; १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; १६. ७, १३.
जहानि १३. १, १२.
जहामि १०. १, ३२.
जहासि ६. २६, २.
जहि १. ८, ४; ३. १, ४; १९, ८; ८. ४, २२; २४; ९. २, १०; ११. १२, २१; १९. २९, ९^{४}; ३४, ९; २०. ८, १; ४३, १.
जहि १. ८, ३; २१, २; ३; २. २७, १; २; ३; ४; ५; ६; ७; ३. २, ४; ४. १७, ४; ३२, ३; ५. १४, १; २^{३}; ९; २१, १; २३, २; २९, १०; ६. २, २; ६, २; २६, ३; ३७, २; १०१, १; १३४, ३; ७. ९३, १; ११४, ४; ८. ३, ७; २३; ४, १९; ५, १५; १०. १, ६; ३१; ४, ३; १३; ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २०; २१; ११. १, ९; २, २१; १२, २१; १२. १०, १४; ११, ६; ९; १३. १, ३०; ३२^{२}; १६. ७, १२; १९. १५, १; ३०, १; ४७, ८; ५०, १; ६५, १; २०. ५, ३; ७४, ७; ९३, १.
जहिमः ६. २६, २.
जहीत १२. २, २६; २७.
जहीतम् ७. ५५, २.
जहीतात् ११. १, १२.
जह्याः १९. ५०, १.
जह्युः ६. ४७, २.
जा ५. ११, १०^{२}.
जाःऽपत्यम् ७. ७७, १०.
जागरत् १९. २४, २; ३.
जागरासि १४. २, ३१.
जागार ५. १९, १०; ११. ६, २५.
जागृत १. ३०, १.
जागृतम् ८. ४, २५.
जागृतात् ४. ५, ७.
जागृताम् ५. ३०, १०.
जागृविः ५. ३०, १०; ८. १, १३.

जागृविम् २०. २०, १; ९७, ४.
जागृहि १९. ४७, ९.
जागृहि २. ६, ३; ३. १९, ७; १२. २, १०; १३. १, ९; १४. १, २१.
जाग्रत् ६. ११९, २; १६. ७, १०,
जाग्रतः ६. ४५, २; ९६, ३; ७. ११३, २.
जाग्रति १९. ४८, ५.
जाग्रति १९. ४८, ५²; ६.
जाग्रतीम् ८. ६, ८.
जाग्रत्ऽदुस्वप्न्यम् १६. ६, ९.
जातः १. २४, १; ३३, १; ३. २०, १; ४. १, ४; २, ७; १०, १; ४; ५²; ११, ३; ३४, १; ५. ४, ७; ८; १२, ११; २२, ५; ६. ११०, २; ९. १, ५; १०. ६, २; ७, ३६; ८, २७; २८; ११. ७, ५; १९. ६, ७; ९; ३९, ५; ४२, १; २०. ३४, १; ९३, ५; १२१, २.
जातम् १. २८, ३; ४. ६, ८; ९, ९; १७, ३; २३, ७; ५. ४, २; २८, ६; ७. ६, १; ८. २, ४; ६, १८; ९. १, ५; १०. १०, २१; ११. ७, ३; ५; २३; १९. ६, ११; ४१, १; ४४, ३; ४५, ३; ५३, ९; २०. २५, ५; ८१, १; ९२, २०; ९३, ४; ९६, १३.
जातम्ऽइव ३. ३०, १.
जातऽवेदः १. ७, २; ३. १०, ६; ५. ८, २; ६. ७७, ३.
जातऽवेदः १. ७, ५; ६; ८, ४; ९, ३; २. २९, २; ३. १९, ८; २२, ४; ४. २३, २; ३९, १०²; ४०, १; २; ३; ४; ५; ६; ७; ८; ५. १२, १; २७, १२; २९, १; २; ३; १०; १२; १३; १४; ६. १४०, १; ७. ३५, १; ३६, १; ७८, ४; १११, १; ११३, २²; १२०, ३; ८. ३, २; ४; ५; ७; ११; २५²; ४, १४; ११. १, ३; ४; १२, ४; १३. १, १५; १८. २, ४; ५; ८; ९; ३५; ३, ४२; ७१; ४, ११; १९. ६४, २; ६५, १; ६६, १.
जातऽवेदसः ८. २, १३; १८. ४, १; १२; १३; १९. ४५, ३.
जातऽवेदसम् ४. २३, ४; १२. २, ७; १३. २, १६; २०. ४७, १३; ६७, ३².
जातऽवेदसि २. १२, ८; १०. ३, १९; ६, ३५; ११. १, २९.
जातऽवेदसे १९. ६४, १; २०. १३, ३.
जातऽवेदाः ३. १, १; २, १; ४. १५, १०; ३२, २; ३४, २; ५. ११, २; ३; ६. १२३, १; ७. ८५, ५; ८७, ४; ८९, १; ८. १, ११; ९. ४, ३; १२. २, ८; १३. १, १२; १४. १, ४९; १८. १, २७; २८; ४, ६४; ६५; १९. ३, १; ४, १; १६, २; २७, १५; ६४, १.
जातस्य १९. ६, १६.
जाता ५. १३, ८; ६. १३३, ४; १३६, १; ८. ९, १६; २१; १०. ८, ३०; १९. ४, १; ४९, ३.
जाताः २. १४, ५; २८, ३; ७. १२०, ३; १०. २, ११; ११. ७, २०; २१; १०, १०; १२. १, १५; १८. ४, ५७; १९. ६, १२.
जातान् ६. १३६, २; ७. ३५, १; ८. ६, १९; १०. ३, १३; १५; ११. १, २६; ११, ६.
जातानाम् ३. २३, ३.
जातानि १. १६, ३; १०. ४, २३; २०. ९३, ८.

जातायाः ८. ६, १; १०, १.
जातायै १०. १०, १.
जातासः १८. १, ३२.
जाते २०. ५८, १.
जातेन ५. ११, २; ३.
जातौ ८. ९, १.
जानताम् ६. ६४, १.
जानते ४. ३६, ८.
जानन् ३. २०, १.
जानन्तु ६. ११२, १; ७. ६२, २; ३; १०. ५, ५०; १८. ४, ५१; ५२.
जानम् ७. ८१, १.
जानात् ३. २, ६.
जानाति ८. १२, ४; ६; १५. १२, ५; ९.
जानातु १९. ४, ४.
जानानाः १२. ३, ४०.
जानामहै ७. ५४, २.
जानामि ९. १५, १५; १०. ७, ४३.
जानीत ६. १२३, २.
जानीत ६. १२३, १.
जानीतात् ९. ५, १९.
जानीध्वम् ६. ६४, १; ११. १, ५.
जानीमः ८. ७, १८.
जानीहि १०. १, २५.
जानीहि १०. ८, ५.
जानु १८. १, ५२.
जानुनोः १०. २, २.
जानुऽभ्याम् ९. १३, २१; १०. २, ३.
जामयः १. ४, १; १४, ४; १७, १; १४. २, ६१; १८. १, ११; ४, ६६.
जामि १८. १, ४; २०. १३८, ३.
जामिः ५. ३०, ५.
जामिऽकृत् ४. १९, १.

जामिम् ६. १२०, २; ७. १०४, १; १४. २, ३३.
जामिऽशंसस्य ९. ४, १५.
जामिऽशंसात् २. १०, १; २; ३; ४; ५; ६; ७; ८.
जाम्याः २. ७, २.
जाम्यै ५. १, ४.
जायताम् ६. १०६, १.
जायताम् ३. २३, २; ३; १३. १, ५४; १४. २, १५; २१; २०. १७, ९.
जायते ८. ३, १२; ९. १३, ८; १०. ५, ४८; १२. ४, १४.
जायते ५. १७, १३; १६; १९, ४; ९. ३, २०; १०. ८, १३; ११. ६, १४; २०; १२. ४, ९; १०; १३. २, २५.
जायध्वम् ३. १४, ४; ५.
जायन्ताम् २. १३, ५; ४. १५, २; ३.
जायन्ते ११. ६, ३; १६; १७.
जायमानः ६. ११०, ३; ७. ८६, २; १३. ३, २२; १४. १, २४; १९. ३२, ९; २०. ८८, ४; १२७, १०.
जायमानम् ३. ११, ८; ८. ६, २५; ९. १४, ४.
जायमानस्य ४. २, ८.
जायमाना १२. ४, १०.
जायमानाः २. १, १; १४. २, २५.
जायमानात् १०. १०, २३.
जायमानायै १०. १०, १.
जायमाने २०. ९२, १९.
जायया १२. ३, १७.
जायसे ७. ८१, १; १३. २, ३.
जायसे ७. ८६, १; १४. १, २३.
जायस्व ११. १, १.

जाया ३. ३०, २; ५. १७, ६; १२; ६. २२, ३; १०. १, ३; ११. १०, १७; १२. ३, ३९; ४७; १४. १, २९; ३०; २, ३; १८. १, ५३; २, ५१.
जायाऽईव १८. १, ८.
जायाः ३. ४, ३; ४. ३७, १२; १४. २, ३९.
जायान्य ७. ८१, १[२].
जायान्यः ७. ८०, ४; १९. ४४, २.
जायान्यम् ७. ८०, ३.
जायाम् ५. १७, ९; ६. ६०, १; ७८, १; ३; ८२, २; ३; ११८, ३; ९. ५, ३०; ११. १०, १; १४. १, ५६; २, १; ३९.
जाये १२. ३, ३९.
जायेते इति १०. ८, २३.
जायेमहि ४. ३३, ४.
जारः १८. १, २३; २०. ९६, १५.
जारम् २०. ८९, २.
जारिषुः २०. ६७, २[२].
जालऽदण्डम् ८. ८, १२.
जालऽदण्डाः ८. ८, ९.
जालम् ८. ८, ५; ६; ७; ८.
जालाषम् ६. ५७, २.
जालाषेण ६. ५७, २[२].
जालेन १०. १, ३०.
जाल्मः ४. १६, ७.
जाल्माः १२. ४, ५१.
जाष्कमदाः ११. ११, ९.
जिगत्नुम् ५. २, ६; २०. १०७, ९.
जिगात २०. १३, २.
जिगाति ८. ४, १७.
जिगाति २०. ५१, २.
जिगार्य ४. २३, ५; २०. ११, ४.
जिगाय ३. १०, ४; ७. ८५, १; ८. ९, ११.
जिगीर्षति ११. ७, १८.
जिगीवान् ४. २२, ६; ७; ८. ५, २२; २०. ३४, ४.
जिग्यथुः ७. ४५, १.
जिग्युः ५. २९, ११; ८. ३, १८.
जिग्युषः २०. २७, ६; ५९, ३.
जिग्युषे २०. ९८, २.
जिग्ये ७. ४५, १.
जिघत्सः ५. १८, १.
जिघत्सतः ६. १४०, १.
जिघत्सति ५. १९, ६.
जिघत्सुऽभ्यः ८. २, २०.
जिघत्ऽस्वम् २. १४, १.
जिघर्मि ८. ३, १.
जिघांसति ४. १८, ३; ७. ८२, २; ८. ५, १५; १२. ४, २९; ३०; २०. ९५, ४; ९६, १३; १५; १६.
जिघांसन् ६. ९९, २.
जिघ्नते २०. ५, २.
जिघ्नसे २०. ६१, ६; ६२, १०.
जिज्ञासे १४. १, ५६.
जिज्यासतः १. २१, ४.
जितम् ६. ९८, ३; १०. ५, ३६; ११. ११, ४; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; ९, १; १९. १३, १.
जिता १. २४, १.
जिताः ४. २४, २; ११. १२, १५.
जितिम् १०. ६, १६.
जिते ११. १२, ७.
जिनतः ६. १३४, ३; १२. ५, ५; ६, ५.
जिनताम् १२. १०, १०.

जिनाति ६. १३४, ३^{२}; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.
जिनीयात् १२. ४, १५.
जिन्व ७. ३२, १.
जिन्वत् १२. १, ४६.
जिन्वतम् ८. ४, ६.
जिन्वतात् १०. ६, ३४.
जिन्वति ८. ९, १३; १२. १, २.
जिन्वतु ३. ५, १.
जिन्वथ १. ५, ३.
जिन्वन्ति ९. ४, १८.
जिन्वसि ११. ६, १४, १६.
जिन्वितः १९. ३१, ७.
जिविः ८. १, ६; १४. १, २१.
जिष्णवे १०. ५, १; २; ३; ४; ५; ६.
जिष्णु ३. १९, ५.
जिष्णुः ३. १९, १, ११. ११, १८; १९. १०, ५.
जिष्णुना १९. १३, ३.
जिष्णुम् २०. ९१, ९.
जिष्णोः २०. १३७, ३.
जिहताम् १. ११, १.
जिहिंसिम ६. १२०, १.
जिहिंसीः १२. ३, १८.
जिहीड ४. ३२, ५.
जिहीडे ६. ११६, २.
जिहीते १२. १, ४८.
जिहीध्वे ८. ७, २१.
जिहीर्षति २. २५, ३; ५. २९, १५.
जिहीष्व ५. २५, ९; ६. १२१, ४.
जिह्मः १२. ४, ५३.
जिह्वया १. १०, ३; ५. २७, ९; ६. ५६, ३; ८. २, ३; ३, २; ११. २, १७; ४, ५^{२}; २०. ४, २.
जिह्वरः १८. ३, ५३.
जिह्वा ४. १३, ७; ५. १८, ८; ३०, १६; ७. ३०, १; २; ८. १, १६; ९. १२, ३; १०. ९, ३; ११. ४, ५; २०. १६, ६.
जिह्वाः १०. १०, २८.
जिह्वाभिः ६. ७६, १.
जिह्वाम् ५. २९, ४; ६. ५६, ३; १०. २, ७; ७, १९; ११. १०, १५; १९. ३२, ४.
जिह्वाऽमूले १. ३४, २.
जिह्वायाः १. ३४, २; २. ३३, १; २०. ९६, १७.
जिह्वायै ११. २, ६.
जीजनत् २०. ७७, ३.
जीजनन् १८. १, २०.
जीतम् १२. १०, ११.
जीतस्य ५. १९, १३.
जीताय १२. १०, ११.
जीमूताः ११. ७, १४.
जीयते १. २०, ४; ५. १९, ६; ११. ५, ७.
जीयते ११. ५, ६.
जीरऽदानवे २०. १७, ८.
जीरऽदानुः ७. १९, २; १८. ३, ६१.
जीर्णः १०. ८, २७.
जीर्यति १०. ८, ३२.
जीव २. १३, ३; १९. २४, ५; ६; ७०, १^{२}.
जीव २. २९, ७; ३. ११, ४; ३१, ८; ७. ५५, २; १४. १, ५२; १९. २७, ८^{३}; २०. ९६, ९.
जीवः ६. ४६, १; ९. १५, ८; १४. २, ४४.
जीवतः २०. ९६, २४.

जीव॑तःऽजीवतः ५. ३०, ७.
जीव॑ता ९. ५, ७.
जीव॑ताम् ८. २, २; ९. ३, ९.
जीव॑ति ५. ५, २.
जी॒व॒ति॒ ३. २९, ४; ५; ८. २, २५; १८. ४, ३२.
जीव॑तु ५. २९, १३.
जी॒व॒तु॒ ८. २, ५.
जी॒वऽध॑न्याः १२. ३, २५.
जी॒व॒ऽध॒न्याः १२. ३, ४.
जीव॑न् ५. ८, ४; १८. २, २०; १९. २४, ६.
जीव॑नम् ९. २, ५; १६.
जीव॑नाय ३. ११, १; ४. ९, १; ८. २, २५; १२. २, २४; २०. ९६, ६.
जीव॑न्तः १२. २, २३; १८. २, २९.
जी॒व॒न्तः १९. ३९, ३.
जी॒व॒न्ति॒ ८. १३, ४; ८; १२; १६; १४, ४; ८; १२; १६; ९. १, २०; १५, १९; १०. १०, ३४; ११. ७, १२; १२. १, २२; २, ५०.
जीव॑न्तीः ३. १४, ६.
जी॒व॒न्तीम् ८. २, ६; ७, ६.
जीव॑न्तौ १२. ३, ३५.
जी॒वऽपु॑त्रौ १२. ३, ३५.
जी॒व॒ऽपु॒राः २. ९, ३; ५. ३०, ६.
जी॒वऽब॑र्हिः ११. ९, ७.
जी॒वऽभो॑जनम् ४. ९, ३.
जी॒वम् ४. ९, १; ६. १०९, २; ९. १५, ८; १२. ३, ४; १४. १, ४६; १८. ४, ५१.
जी॒वय॑थ ४. १३, १.
जी॒व॒ला १९. ३९, ३.
जी॒व॒लाः १०. ६, ३; १२. ३, २५; १९. ६९, ४.
जी॒व॒लाम् ६. ५९, ३; ८. २, ६; ७, ६.
जी॒व॒ऽलो॒कम् १८. २, ६०; ३, २; ४.
जी॒वसे॑ ६. १९, २; ४१, ३; ५७, २; ११. ६, ९; २६; १८. २, ३; २३; ३, ६३; ४, ५४.
जीवा॑ः २. २८, ४; १९. ७०, १.
जी॒वाः ३. १४, ६; ६. ११७, २; १२. २, २२; १८. २, २७; ३, ६७; ४, ५७; ८७; १९. ६९, १; २०. ७९, १.
जी॒वा॒त् १८. १, ६.
जी॒वात॑वे ६. ५, २; ८. २, ९.
जीवा॑ति १४. २, २; ६३.
जी॒वा॒ति॒ १. १०, २; २. २९, २.
जी॒वातु॑म् ७. १८, २; ८. १, ६.
जी॒वान् १८. ४, ५०.
जी॒वान् १२. ३, ३४.
जी॒वाना॑म् २. ९, १; २; १२. २, ४५.
जी॒वा॒नि॒ ५. १८, २.
जी॒वाम् १८. ३, ३.
जी॒वासः॑ १२. २, ३०.
जीवितम् ६. १३४, १.
जी॒वि॒त॒ऽयो॑पनः १२. २, १६.
जी॒वि॒त॒ऽयोप॑नान् २. २५, ४; ५.
जीवि॑तवै ६. १०९, १.
जी॒वि॒षुः ९. २, १०.
जीवीः ५. १३, ४.
जी॒वी॒त् १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; १६. ७, १३.
जीवेभ्यः॑ ६. ११७, २; ८. १, ७; १५; १२. २, २३; १८. ४, ५३.
जीवे॑म १९. ६७, २.
जी॒वे॒म ३. १२, ६; १८. ४, ७०.
जी॒वेषु॑ १. ३५, २; १८. २, ३; ५२.

जी॒वौ १४. २, ४३.
जी॒व्यासं॑म् १९. ६९, १; ४; ७०, १.
जी॒व्या॒स॒म् १९. ६९, १; २[२]; ३[२]; ४; ७०, १.
जु॒गु॒पुः १९. २७, ९; १०.
जु॒जु॒षा॒णः १८. २, २१; २०. ९७, २.
जु॒जु॒षा॒णम् २०. १२, ३.
जु॒जु॒ष्ट॒न ७. ८२, १.
जु॒जोष॑ २. २६, १.
जु॒षतां॑म् ६. २७, २.
जु॒षध्वं॑म् १८. १, ५१.
जु॒ष॒ध्व॒म् ११. १२, १४; १९. २७, ११; १२; १३.
जु॒ष॒न्ता॒म् १. १५, १; ३. ८, २; १५, २; ५. २७, १२; ७. १८, ४; २९, १; १८. २, ३१; ४, १३; ४०; १९. ११, ४.
जु॒षमा॑णः १९. ३, १.
जु॒षसे॑ १८. ३, ९.
जु॒षस्व॑ २. ५, १; ७. २१, २; ४८, १; ७०, १.
जु॒ष॒स्व॒ २. ५, ४; ४. ३९, १०; ५. २९, १४; १८. ३, ४; १९. ६४, ३; २०. ६, ८; ११७, ३.
जु॒षा॒णः ४. ३८, ५; ६. ८३, ४; १२५, ३; ७. ७६, १; १०९, १; ११४, ५; १०. ६, ३५; २०. ८७, २; ९६, २.
जु॒षा॒णाः ७. ७७, ३; १०२, ४; ११४, २; ९. २, ८.
जु॒षा॒णौ ७. ३०, २.
जु॒षेत॑ २०. ७२, ३.
जु॒षे॒त ७. ४९, २.
जु॒षेथां॑म् ५. ६, ८.
जु॒षे॒था॒म् ३. १५, ४; १७, ७.
जुष्टः॑ ७. ७७, ९.
जुष्ट॑म् ४. ३०, ३.
जुष्टा॑ २. ३६, १; ४.
जुष्टा॑म् ५. ७, ४.
जुष्टि॑म् ४. २४, ५.
जु॒हाव॑ २०. १४०, ५.
जु॒हु॑ १८. ४, ६.
जु॒हु॒त ६. ३२, १.
जु॒हुमः॑ ७. ८४, ४; ८५, ३.
जु॒हु॑यात् १५. १२, ३.
जु॒हु॒यात् १५. १२, ३.
जु॒हु॒राणः १८. १, ३३.
जु॒ह्वः॑ १८. ४, ५.
जु॒हूमसि॑ २०. ५७, १; ६८, १.
जु॒होत॑ १८. २, २.
जु॒होत॑न ७. ७५, १; २०. ८७, १.
जु॒हो॒त॒न ७. ४८, २; १८. २, ३.
जु॒होति॑ ७. ७३, १; २; १५. १२, ४; ७; ८; ११.
जु॒हो॒ति ९. ७, ४.
जु॒होमि॑ ४. ३२, ७; ६. ८३, ४; ८४, १.
जु॒हो॒मि १. १५, १; ३१, ३; २. २६, ३; ३५, ५; ३. १५, ३; ४. ३९, ९; १०; ६. ६४, २; ११६, १; ९. ४, १०; ५, ३८; १२. ३, ५४; १३. १, १३; १८. ४, २८; ३५; १९. १, १; २; ३; ५८, ५.
जु॒ह्वतः॑ ३. १०, ११; ६. ११४, ३; १७. १, १८.
जु॒ह्वति॑ ४. ४०, १; २; ३; ४; ५; ६; ७; ८.
जु॒ह्व॒ति १७. १, १८.
जु॒ह्व॒म् ५. १७, ५.
जु॒ह्वा॒ऽ २०. ३५, ५.
जूतिः॑ १९. ५८, १.
जूति॑म् २०. ११, २.
जूति॑ऽभिः १३. २, १५.

जूतिऽमान् १२. १, ९८.
जूर्णि २. २४, ९.
जेता ५. २०, १२; ६. २, ३; २०. २०, ७; ९७, १०.
जेतारम् २०. १०९, ३.
जेत्वानि ६. १२९, १.
जेष्यन् ५. २०, १.
जेहमानाः १८. ३, ४७,
जैत्रम् १९. १३, ९.
जैत्रा २०. ६१, ६; ६२, १०.
जैषुः ४. ३८, ३.
जोगुवानः २०. ३९, १४.
जोषम् २०. ३१, २.
जोषयन्ते २०. २९, २.
जोषसे १९. ४९, ६.
जोहवीति १०. ७, ३१.
जोहवीतु ६. ७३, ३.
जोहवीमि २. १२, ३; ३. २१, ३.
जोहवीमि ३, १६, ९; ४. २३, ७; २४, ७; २६, ७; २७, ७; २८, ७; २९, ७; ७. ४९, १; ११. १, २६; १९. ४, १; २०. ९९, १.
ज्ञातयः ४. ९, ६; १४. १, २६.
ज्ञातात् १९. १९, ६.
ज्ञातारम् ६. ३२, ३; ८. ८, २१.
ज्ञातिऽमुखाः १८. २, २८.
ज्ञातीन् १२. ९, ६.
ज्ञेषम् ९. ५, १६.
ज्मः २०. ८८, १.
ज्यया १. १, ३.
ज्या ५. १८, ८.
ज्याकाः २०. ९९, २; ३; ४.
ज्याऽके १. २, २.
ज्याऽघोषाः ५. २१, ९.
ज्याऽपाशैः ११. १२, २२.
ज्याम्ऽइव ४. ४, ७; ५. १३, ६; ६. ४२, १; १०१, ३.
ज्यायस्वन्तः ३. ३०, ५.
ज्यायान् ९. २, १९; २०; २१; २२; २३[३]; २४; १९. ६, ३.
ज्येष्ठः २०. ९२, १६; १०९, ४.
ज्येष्ठः १०. ८, २८; १८. १, १९.
ज्येष्ठऽघ्न्याम् ६. ११०, २.
ज्येष्ठतः ११. ४, १.
ज्येष्ठऽतातये ६. ३९, १.
ज्येष्ठम् ५. २, १; ९. १९, ४; १९. २२, २१; २३, ३०; ९३, ८; २०. ८०, १; १०७, ४.
ज्येष्ठम् ५. १, ८; ६. ११२, १; १०. ७, १७; २४; ८, १६; १९; २०; ११. ७, ९; २३; १०, ९; ६; १५. १, ३.
ज्येष्ठऽराजम् २०. ४४, ३.
ज्येष्ठऽवरः ११. १०, १; २.
ज्येष्ठस्य १२. २, ३९.
ज्येष्ठा १९. ७, ३.
ज्येष्ठाय १०. ७, ३२; ३३; ३४; ३६; ८, १.
ज्यैष्ठ्याय २०. ६९, ४.
ज्योक् १. ६, ३; १४, १; ३; ३१, ४; ४. २१, ३; ६. ६२, ३; १२. २, १८; ४९; १८. २, २९; १९. २४, २; ३.
ज्योतय ७. १७, १.
ज्योतय ४. ३७, १०.
ज्योतिः १. ९, २; ३५, ३; २. ११, ५; ४. १४, ३; १८, १; ५. १२, ७; १३, ३; ६. ९२, ३; ७. २३, १; ९९, ७; ८. १, ८; २१; २, २; ५, १७; ६, १४; ९. ९,

७; ११; २६; १०. १, १६; ११. १, २८; १२. १, १९; ३, ९०; १३. २, ९; ३६; ३, ११; १७; १६. २, ५; १८. १, ३९; ३, ६४; ६७; १९. १९, ४; २०. ११, ४; १९, ३; १६, ११; १७, ४; ८; ४६, १; ९८, ४; ६९, ३; ७७, ४; ७९, १; ९१, ४; १०.

ज्योतिःऽअग्राः १४. २, ३१.

ज्योतिःऽअनीकः १९. १०, ४.

ज्योतिःऽकृत् १३. २, १९; २०. ४७, १६.

ज्योतिषः ४. १, ५; १०, १; ६. ३६, १; २०. ८८, ४.

ज्योतिषा ८. ३, २१; २४; १०. २, ३१; ११. १, ३७; १३. १, ११; २, ४९; १६. ९, ३; १७. १, २७; २८; १८. ३, ७; २०. १६, ५; १७, ९; ६२, ७.

ज्योतिषाऽइव ४. १९, ३.

ज्योतिषि १. ९, १.

ज्योतिषीऽमान् १८. ४, १४.

ज्योतिषे ६. ६१, १.

ज्योतिष्मतः ९. ११, १४.

ज्योतिष्मती १९. ४०, ४.

ज्योतिष्मतीः ४. ३५, ५; १०. ५, ३८.

ज्योतिष्मन्तम् ९. ५, ६.

ज्योतिष्मान् १२. ३, ६; १६; १३. २, ३३; ३४; २०. १०७, १३.

ज्योतींषि ९. ५, ८; १०. ७, ४०; १०, १९; २०. ६१, २.

त

तंस्तनीहि ५. २०, १.

तक्मन् ५. २२, ६; ७; १२.

तक्मन् १. २५, १; २; ३; ५. २२, २; ५; ७; १०; ११.

तक्मनः ५. ३०, १६.

तक्मना ११. २, २६.

तक्मऽनाशन ५. ४, १.

तक्मऽनाशनम् ५. ४, २.

तक्मने १. २५, ४^{२}; ५. २२, ४; ८; ६. २०, १; २; ३.

तक्मा ४. ९, ८; ५. २२, ९; ११. २, २२; ६, ११; १२. ८, ४.

तक्मानम् ५. ४, १; ९; २२, १; ३; १३; १४; ९. १३, ६; १९. ३४, १०; ३९, १; ५; ६; ७; ८; १०.

तक्रः २०. ९२, १०.

तक्षकः ८. १४, १४.

तक्षत् २०. ३५, ६.

तक्षतम् ८. ४, ४.

तक्षती ९. १९, २१.

तक्षा १०. ६, ३.

तङ्ल्वाति ८. ६, २१.

तण्डुलः १०. ९, २६.

तण्डुलम् १२. ३, १८.

तण्डुलाः ११.१, १८; ३, ५; १२. ३, ३०.

तण्डुलैः १२. ३, २९.

तत् १. १६, २; १८, ३; २४, १; ३२, १; २; ३; ४; ३५, १; ३; २. १, १; २; ३, १; ३^{२}; ४^{२}; ५^{२}; ७, २; २५, ५; २८, २; ३०, ४^{२}; ३१, ५; ३. २, ४; ४, ५; ९, २; ३; १३, २; १५, ५; २२, १; ५; २३, १^{२}; ३०, ४; ४. १, ६; ७, ७; ८, ३; १०, ७^{२}; ११, ११; १२, २; १६, २; ५; १७, ६; ७; १८, ८; १९, ६^{२}; २०, १; ३७, ३; ४; ५; ५. १, ५; ७; २, १; ६; ४, १०; ६, २; ४; ८, २; ६; ११, ६; १०^{२}; १३, २; ९; १७, ९; १८, १४;

१९, ५; ६; ८[२]; १२; २२, ११; २५, ६; २७, १०; २८, ६; २९, २; ३; ५; ६; ७; ८; ९; ३०, १३; **६.** ११, १[२]; २[३]; २३, १; २४, १; २; २९, २; ५४, १; ६३, १; ६९, १; ३; ७१, १; २; ९८, ३; ११६, १; ११७, १; २; ११८, १; ११९, ३; १२२, ५; १२४, २; ३[२]; १४१, २; १४२, २; **७.** ५, ३; १३, ४; २५, १; २७, २; ७; ३०, १; ४५, १; ५५, ३[२]; ५८, १; ५९, १; ६७, २; ३; ६८, १; ७३, १; २; ७६, १; ७७, ७; ८०, ४; ८२, १; ८४, ४; ८५, ३; ९५, २; ३[२]; १०६, १[२]; **८.** २, ३; १२; १३[२]; १६; ३, २१; ४, ३; १२; ५, ५[३]; १९; ६, २०; २६; ११, २; १३, १६; १४, १६; १५, १; ३; **९.** १, २[२]; १८; २४; २, २; ३, २; १५; ४, ४; २०; ५, १३; १९; ६, ७; ८; ११; १३; ८, ८; ९; ११, १; २; ५; ६; १४, १३; २१; १५, १; ४; १८[२]; २३; **१०.** १, १९; २, २; ३; ५; ७; २७[२]; ३२; ४, १०; २५; ५, ४०; ५०; ७, ८; २५; २६; २८; ३१; ८, ४; ७; ९; ११[२]; १६[२]; २४; २९[२]; ३३; ३४; ४१; ४३; ९, २६; २७; १०, ११; १७; **११.** ३, २५; ६, ५; ७, १०; १५; ८, २३[२]; ९, ५; ७; १२; १४; १९; १०, ६; १४; १५; १६; १७; २९; ११, १; १२, १७; **१२.** १, ३५; ४६; ५८[२]; ६१; २, ५; ३६; ३, १; ३; १९; २२; ३९[२]; ४, १; ११; ३१; ४०; १०, ४; **१३.** १, ४४; ५२; २, ३[२]; १४; **१४.** १, १५; १६; ३०; ५६; २, १२; २२; ५१; ६६; ६९; **१५.** १, २; ३[०]; ६; १०, १; ११, १; १२, १; १३, १; ३; ५; ७; ९; १४; १७, २; ९; १०; **१६.** १, ८; ६, २; ३[२]; ११; ९, २[२]; **१८.** १, ४; ३२; २, २६; ३३; ५२; ३, ३; २४; ५५; ४, ३१; ३७; ४९[२]; ५१; ६४; **१९.** ३, ४; ६, ६; ९, १४[२]; ११, ६[२]; १३, ३[२]; २०, ३; २४, ८[३]; २६, २; ४[२]; ४०, १; ४१, १; ४४, १; ४६, १; ५२, १; ४; ५; ५३, ९; ५७, ३; ५; ५९, २; ३; ६४, ३[२]; **२०.** ९, ३[२]; ४; १५, ४; १६, ८; १७, ५; ३६, ४; ४१, २; ४३, १; २; ३; ४५, १; ४९, ६[२]; ७; ६१, ३; ६३, ६; ६७, २; ७८, १; ९१, ११; ९२, १०; १०७, २; ४; ९; ११२, १; २; ११८, २; १२३, १[२]; २; १३९, २; १४१, ३; १४३, ९.

तत **१८.** ४, ७७.

तर्तः **१.** १०, १; **३.** ४, २; ४; **४.** ४, ३; ९, ४; १९, ४; ६; ३०, ७; **५.** १, २; २४, १७; **६.** १८, ३; ८९, १; ११३, १; ३; १३१, ३; **७.** ५८, ३; ८८, १; २; १११, १; **८.** ९, ६; **९.** २, १९; २०; २१; २२; २३; २४; १५, ३; **१०.** १, २९; ३, ८; ८, २५; १०, १८; १९[२]; २२; **११.** ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; **१२.** ४, ७; ८; ९; ३१; **१३.** २, १५; **१४.** १, ४; **१५.** ६, १९; ८, १; **१८.** २, ३२; **१९.** ३, १; ५, १; ६, ३; १५, १; ३०, ५[२]; ३९, ६; ७; ८; ४१, १; ५६, २; ५७, ५; **२०.** ६, ९; २०, ४; २५, ५; ५७, ७.

ततक्ष **२.** ५, ६; **११.** ७, ८; **१४.** १, ६०[२].

ततक्षुः **५.** १, ६; **२०.** ५४, १.

ततपं ८. ४, १५.
ततम् ६. १२२, २.
ततर्दं २. ५, ५; ७. ४२, १; १०. २, ६.
ततर्हे ११. ७, ७.
ततस्रे २०. ८८, २.
ततस्रे २०. ७२, २; ७५, १.
तताः ५. २४, १६.
ततानं २०. १२, १.
ततान ७. ८७, ५; १३. १, ६; १८. १, २८; १९. २२, २१; २२, ३०.
ताताप ७. १९, २.
ततामह १८. ४, ७६.
ततामहाः ५. २४, १७.
ततिं १२. ३, २.
ततिऽधा १२. ३, २.
तर्तुरिम् २०. ३६, २.
तर्तृपिम् २०. ६, २; ७, ४.
ततृपुः ११. ९, १२.
ततृपुः १८. ३, ४७.
तते २०. २५, ५.
ततऽतत् २०. ७२, ६.
तत्त्वम् १९. ४२, २.
तत्निरे १४. १, ४५.
तत्निरे ९. १४, ६.
तत्रं १. २५, १; २. १४, ३[२]; ३०, ३; ४. ७, १; ११, ११; १९, २; ५. ४, ३; ४; ८; ६. ११, १; २२, २; ९५, १; २; ९९, २; १०६, १; ११९, ३; १२०, ३; १२३, ५; ७. ५, ३; १९, २; ८१, १; ८. १, ७; २, १५; २४; २५; ६, १; ९. १, १८; ३, २०; १०. १, ८; १९; ७, ८; ९; ८, ४; ६; ११. १, २३; ३५; १२. १, ३४; ३, १; १३. १, ६[२]; ४६; ५३; १४. २, २३; १८. २, ७; ५३; ५५; ३, ८; ९; ५२; १९. ३९, ६; ७; ८; ४३, १; २; ३; ४; ५; ६; ७; ८; २०. ७१, १२.
तत्रति १९. ३६, २.
तत्ऽविदे ९. १, ९.
तत्ऽसिनाय २०. ३५, ४.
तथां ३. ४, ५; ९, १; २; २८, २; ४. ५, ५; ८, ६; ११, ९; ५. ८, ८; १७, ३; १८, १४; २९, २; ३; ६. ४६, २; ९. २, १८; ५, १४; १०. १०, २७; १२. ४, ४; १४; ३३; १५. १०, २[२]; ४; ११, २[२]; ६; ८; १०; १६. ५, ३; ४; ५; ६; ७; १०; १९. ६, २; ८; ४६, ७; ५७, ४; ६४, २.
तदा ११. ६, ४.
तदानीम् १०. ८, ३९; १२. १, ५५.
तदित्ऽअर्थाः २०. १८, १.
तदुरि ४. १५, १५.
तनयाय २०. १४१, १.
तनां ८. ४, १०; ११; २०. ८४, १.
तनायाः ७. ७७, ५.
तनु १. १, ३; ७. ९५, ३[२].
तनुते २०. १२३, १.
तनुषे १३. २, १०.
तनुष्व ५. २, ४; २०. १०७, ७.
तनू इति ४. २५, ५.
तनूः २. १३, ४; ४. ३२, ५; ६. ९२, ३; ११. ६, ९; १२. ३, २२; १४. १, २७; २, ५०; १७. १, १३; १९. ३, ३; ६१, १.
तनूऽजस्यं १. २३, ४.
तनूऽजाः ६. ४१, ३.
तनूऽत्यजः १८. २, १७.
तनूऽदूषिः १६. १, ३.

तनूऽदूषिम् १४. १, ३८; १६. १, ७.
तनूऽनपात् ५. १२, २.
तनूऽनपात् ५. २७, १.
तनूनाम् ८. ४, १०; १९. १३, ८; २०. ६३, २; ६९, ८; १२४, ९.
तनूऽपा २०. १४१, १.
तनूऽपाः ६. ४१, ३; ५३, २; २०. ८३, २.
तनूऽपानः २. ११, ४; ३. ५, ८.
तनूऽपानम् ५. ८, ६; ८. ५, २०; ११. १२, १७; १९. ३०, ४.
तनूऽबलम् ९. ४, २०.
तनूभिः ४. १५, १०; ५. ३, ७; ६. ५३, ३; १४. २, ३२; १८. ४, १०.
तनूभ्यः १. १३, २; २६, ४.
तनूम् १८. १, १३; १४.
तनूऽवशिन् १. ७, २; ५. ८, २.
तनूऽवशिन् ४. ४, ४; ८.
तनूऽवशी ७. ११४, १.
तनूषु ७. ४३, २[२]; १९. २०, ३.
तनोत ३. १७, २.
तनोतु ३. १२, ४.
तनोमि ४. ४, ७; ३०, ५; ६. ४२, १; २; १०१, ३.
तनोषि ९. ४, ९.
तन्तवः १४. २, ५१; १५. ३, ६.
तन्तुः १०. २, १७; १३. १, ६०.
तन्तुम् २. १, ५; ६. १२२, १; २; ९. ४, १; १२. ३, ५२; १३. १, ६; ३, १९; २०.
तन्तून् ९. १४, ६; १०. ७, ४२.
तन्त्रम् १०. ७, ४२.
तन्द्रयुः २०. ६०, ३.
तन्द्रीः ८. ८, ९; ११. १०, १९.
तन्यतुः ५. १३, ३.
तन्वः १. १, १; २. २९, १; ३. २२, १; २८, ५; ५. १, ७; ४, १०; ६. ४१, ३; ४९, १; ५३, ३; ६२, २; ७४, १; ९१, १; १२०, ३; १२४, २; १४०, ३; ७. ५९, १; १०९, १; ८. ९, २; ९. २, २५; १२. १, १२; १३. ३, १६; ७, १६; १४. २, ३२; १८. २, ८; २४; ३, ५९; १९. ३, २; २०. ६७, ६.
तन्वताम् ४. १५, १६.
तन्वते १२. १, १३.
तन्वते ३. १७, १.
तन्वन्ति १३. ४, ७.
तन्वम् १. २, २; २. ३१, ५; ५. १, ३; २, ९; ३, १; ६. ९, १; ९२, ३; ११०, १; ७. ३, १; ८. ४, १७; ५, १९; ११. २, २९; १२. ३, ५४; १३. १, ३४; २, २७; ३३; १४. १, २१; ४०; १८. १, ३; ८; १२; २, ३६; ३, ९; ४१; ४, ५२; १९. ५५, ३; २०. ४२, १; ६३, १; १०७, १२; १२४, ४; १३७, ९.
तन्वा १. ३३, ४; ५. ३, ५; ३०, १४; ७. ३, १; १२०, ३; ८. ४, १०; ११; १६. १, १२; १७. १, १३[२]; १८. १, १२; १३; १४; २, १०; ३, ७; ५८; १९. ५०, ३; ६१, १; २०. ११, १; २३, ६; ३७, २; ११.
तन्वाना ५. २६, ६.
तन्वानाः १९. ६, १५.
तन्वाम् १. १८, ३; १९. ३७, २.
तन्वे १. ३, १; २; ३; ४; ५; ६, ३; १२, १; ४; ५. ३, ७; ८. १, ५; २, १६; ९. ३, ६; ५, २६; १२. १, ३०; २०. ४, ३.

तप॑ २०. ३६, ८.
त॒प॒ २. १९, १; २०, १; २१, १; २२, १; ११. १, १६; १८. २, ३६; ४, ११[2].
तप॑ः १. १३, २; २. १९, १; २०, १; २१, १; २२, १; २३, १; ५. १७, १; ६. १३३, ४; ७. ६३, १[2]; २[2]; ८. १३, १५; १६; १०. ७, १; ११; २९; ३०; १०, ३३; ११. ७, २६; ९, ९; १७; १०, २; ६[2]; १२. १, १; ३, १२; १३. ६, १; १५. १, ३; १८. २, १६; ३६; १९. ४०, ३; ४१, १; ५३, ८; १०; ५४, १.
त॒प॒ः १८. २, ३६.
त॒प॒ःऽजाः ६. ६१, १.
त॒प॒ःऽजान् १८. २, १५; १८.
त॒प॒त॒ २. २३, १.
तप॑तम् ८. ४, १.
त॒प॒ति॒ ६. ९१, २; १०. ८, १९; १२. १, २०; ४, ३९; १३. ३, १३; १९. ५३, ६.
त॒प॒तु॒ ७. ७२, १; ८. २, १४; १२. ३, ४३; १८. २, ८; ४, ९[3].
तप॑न् १३. २, १२.
तप॑नः ४. ३६, ६.
तप॑नम् ४. १८, ६; १९. २८, १; ३०, ४.
तप॑न्ति १३. ३, १६.
त॒प॒न्तु॒ ११. १, १६.
तप॑सः ४. ३४, १; ५. ६, ९; ६. १३३, ४; १०. ७, ३६; ११. १, २६; १३. १, १०; १८. २, ८.
तप॑सा ३. १०, १२; ४. ११, ६; ३२, २; ३; ३५, १; २; ५. १७, ६; १८, ८; ९; २८, १; ६. १०४, २; १२२, ४; १३३, ३; ७. ६३, १; ८२, २; ८. ३, १३; ९, ३; १०. ५, ४९; ११. १, १६; ७, १; २; ४; ५; ८; १०; ११; १७; १९; १२. १, ३९; ५, १; १३. २, २५; १७. १, २४; १८. २, १६[2]; १९. ४३, १; २; ३; ४; ५; ६; ७; ८; ७२, १.
तप॑सि १०. ७, ३८.
त॒प॒सि॒ १७. १, १७.
तप॑से १२. ३, ४६.
त॒प॒स्व॒ १८. २, ८.
तप॑स्वतः १८. २, १५; १८.
तप॑स्वान् ५. २, ८; २०. १०७, ११.
त॒प॒स्वी १३. २, २५.
तपां॑सि ५. २६, ७.
त॒पा॒ति॒ ८. १, ५.
त॒पा॒मि॒ ६. १३२, १; २; ३; ४; ५.
तपि॑ष्ठः ११. १, १६.
तपि॑ष्ठाः ८. ३, १९; ११. १, १६.
तपि॑ष्ठेन ७. ८२, २.
तपु॑ः ८. ४, २.
तपु॑ःऽअग्राभिः ८. ३, २३.
तपु॑ःऽवधाय ६. २०, १.
तपु॑ःऽवधेभिः ८. ४, ५.
तपु॑षे १. १३, ३.
तपूं॑षि २. १२, ६.
त॒प्तः ४. ११, ३; ७. ७७, १; २; ५.
त॒प्तम् ७. ७७, ४.
त॒प्ताः १२. ३, २९.
त॒प्तात् ९. ५, ६.
त॒प्य॒ते॒ ९. १४, ११.
त॒प्यन्ताम् २. १२, १.
त॒प्यमा॑नः ११. ७, २६.
त॒प्यमा॑नस्य १९. ५६, ५.
त॒प्यमा॑ना ३. १०, १२.
त॒प्यमा॑ने २. १२, १.

तप्यामहे ७. ६३, २[२].

तम् **१.** ११, २; १६, ४; १९, ४; २०, २; **२.** १, ३; २, १; ११, ३; १२, ३; १३, ५[२]; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; २४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; २५, ३; **३.** ३, ६; ५, ३; ४; ११, २; ८; १६, ५; २०, १; २१, ९; २३, ३; २४, २; २७, १; २; ३; ४; ५; ६; २८, ५; ६; **४.** ३, ५; १६, ६; १८, २; १९, ५; २०, ९; २२, २; ३०, ३[३]; ३१, ५; ३२, ५; ३६, २; १०; ३७, ११; **५.** ४, ६[३]; ६, ११[२]; १२[२]; १३[२]; १४[२]; ७, ५; ८, ५; १२, ९; १३, ३; १४, २; ९[२]; १२[२]; १९, ९; १३; १४; २३, ३; २९, ४; १०; ३०, १२; ३१, १२; **६.** १, २; ५, ३; ६, १; १८, १; २६, २; ३[२]; ३७, ३; ४६, २; ५४, ३; ७५, २; ७७, २; ८१, २; ३; ८५, १; १२३, १; १२७, ३; १३२, १; २; ३; ४; ५; १३३, ३; १३४, ३[२]; १३६, ३; **७.** २, १; ५, ५; ११, १; २२, १; ३२, १; ४१, १; ५२, ६; ७७, ३; ७८, ३; ४; ८०, ३; ८२, २; ९३, १; ९४, १; **८.** १, १०; ३, ५; ७; ८; ११; १७; ४, १६; ५, ११; १५; ६, ९; १८; १४, ८; **९.** १, ५; ६[२]; १४; ४, ३; ७; १८; ५, १६; **१०.** १, ७; ८; २८; २, ३०; ३, ५; १०; ५, १५[५]; १६[५]; १७[५]; १८[५]; १९[५]; २०[५]; २१[३]; २५[२]; २६[२]; २७[२]; २८[२]; २९[२]; ३०[२]; ३१[२]; ३२[२]; ३३[२]; ३४[२]; ३५[२]; ४२[२]; ४३[२]; ४६; ६, ६; ७; ८; ९; १०; १३; १४; १५; १६; १७; १८[३]; १९; २१; २९; ३४; ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १८; १९; २०; २२; २३; ३९; ८, ४४; १०, १२; **११.** २, १३; ३, २२; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ६, २१; ७, ३[२]; **१२.** १, १४; ३०; ४७; २, ३[२]; ४; ७; ९; ३३[२]; ४३; ५४; ३, १२; ३५; ५५; ५६; ५७; ५८; ५९; ६०; ४, ५०; **१३.** १, १७; १८; १९; ४०; ६०; २, ४; १५; ४, ६; १२; ५, ७; **१४.** १, ३८; ४७; **१५.** २, २; १०; १६; २२; ३, १; ६, २; ५; ८; ११; १४; १७; २०; २२; २५; ७, २; ४; ९, २; **१६.** १, ४[२]; ५; ७; ९, ३; ४; ५; ६; ७; १०; ७, ५; १२; १३; **१८.** १, ३४; २, ८[३]; २७; ३, ४; ६; ६३; ४, १३; ५४; **१९.** ६, ११; ३०, २; ३२, १; ३३, ४; **३४**, ६; ३८, १; ४५, २; ४७, ८; ५०, १; ५३, १; ३[२]; ५७, ४; ५८, ४; **२०.** ९, १; १४, ३; १५, ६; २१, २; २४, २; २५, १; ३६, १; २; ३[२]; ५; ७; ४४, ३; ४७, १; ४९, ४; ५५, १; ३; ५६, १; ५९, ३; ४; ६१, १; ४; ६२, ३; ८; ६३, ७; ८; ६४, ६; ६७, ७; ६८, ९; ७२, १; ७५, २; ८७, ४; ८८, १; ८९, ९; ९१, ९; ९२, ८; १४; १७; १८; ९५, ३; ९६, ४; ७; १२; १३; १४; १५; १६; ९९, २; १०२, २; १०५, ५; ११०, ३; ११२, २[२]; १३७, ७; १२; १४३, १.

तमः **१.** २१, २; **८.** १, १०; १६; २१; २, १; २४; **९.** २, १७; १८; **१०.** ३, ९; ७, ४०; **१२.** ३, १८; ४९; ७, १५; **१३.**

१, ३२; २, ८; ९; १९. १२, १; ४०, ४; ४७, १; २०. १६, ५; ११.
तमःऽइव ८. २, १२.
तमःऽवृधः ८. ४, १.
तमसः २. १०, ८; ५. ३०, ११; ७. ५५, ७; ८. १, ८; १०. १, ३२.
तमसःऽइव ५. १३, ३.
तमसा ३. २, ५; ६; ८. ८, ८; १०. १, ३०; ११. १२, १९; १६. ७, १; १८. ३, ३; २०. ९६, १६.
तमसाः ११. ११, २२.
तमसि ८. ४, ३; २०. ९१, ४.
तमस्वति १९. ४७, २.
तमांसि २. २५, ५; ९. २, ४; ९; १०; ५, १; ३; ७; ११; १३. २, ३४; २०. १६, ९; ७७, ४; ८८, ४; १०२, १; १०७, १३.
तमिषीचयः २. २, ५.
तम्ऽतम् ४. ३०, ३.
तया २. २५, २; २७, ५; २९, ७; ३१, १; ३६, ५; ३. २४, ६; २५, १; ३; ४. १७, ४; २०, ४; ५. १८, १५; ६. ६३, २; १०८, ४; १३९, १; ८. ३, १२; ९. २, ५; १०. ५, ४८; ११. ४, ५[2]; १८[2]; ११, २०; १२, ९; २७; १३. १, २२[2]; १५. ११, २; १७. १, १३; १९. ३, ३; ९, ३; ५५, २.
तयोः ८. ४, १२; ९. १४, २०; १०. ७, ४३; ११. ७, ९; ११.
तर २. ६, ५; १८. २, ३१.
तरणिः १३. २, १९; २०. ४७, १६.
तरणिम् १३. २, ४; ३६.
तरत १२. २, २६; २७; २०. ८९, १.
तरन् ७. ४२, १.
तरन्ति ६. १२२, २; १८. ४, ७; १९. ३४, ७; ४४, ६; २०. ५९, ४.
तरसाम् १०. १०, २४.
तरसे ३. १५, ३.
तरस्विनः २०. ५४, ३.
तरस्विनम् २०. ५४, १.
तरांसि १०. १०, २४.
तराणि ४. ३५, १; २; ३; ४; ५; ६.
तराथः १४. २, ४३.
तरामसि २०. ७९, २.
तरी ५. २७, ६.
तरुणः ३. १२, ७.
तरुणम् ९. १, ५; १२. ३, ३७.
तरुता २०. ९२, १६; १०५, ४.
तरुतारम् ७. ९०, १.
तरुष्यतः २०. १०५; १.
तरूणकम् १०. ४, २.
तरेम १९. ५०, ३.
तरेम ६. १२२, १; ७. ५२, ७; १२. २, २६; २७; ४८; २०. १७, १०; ८९, १०; ९४, १०.
तरेयुः १९. ५०, ३.
तर्तूर्यन्ते २०. ८५, ४.
तर्द ६. ५०, २.
तर्दऽपते ६. ५०, ३.
तर्दम् ६. ५०, १.
तर्म १४. १, ४०.
तर्पणम् ९. ६, ६.
तर्पयताम् ६. १३४, १.
तर्पयति १३. ३, ४.
तर्पयथः ४. २६, ६.
तर्पयन्तम् ७. ४०, १.

जूतिऽमान् १२. १, ५८.
जूर्णि २. २४, ५.
जेता ५. २०, १२; ६. २, ३; २०. २०, ७; ५७, १०.
जेतारम् २०. १०५, ३.
जेत्वानि ६. १२५, १.
जेष्यन् ५. २०, १.
जेहमानाः १८. ३, ४७,
जैत्रम् १९. १३, ५.
जैत्रा २०. ६१, ६; ६२, १०.
जैषुः ४. ३८, ३.
जोगुवानः २०. ३५, १४.
जोषम् २०. ३१, २.
जोषयन्ते २०. २५, २.
जोषसे १९. ४९, ६.
जोहवीति १०. ७, ३१.
जोहवीतु ६. ७३, ३.
जोहवीमि २. १२, ३; ३. २१, ३.
जोहवीमि ३, १६, ५; ४. २३, ७; २४, ७; २६, ७; २७, ७; २८, ७; २९, ७; ७. ४९, १; ११. १, २६; १९. ४, १; २०. ५५, १.
ज्ञातयः ४. ५, ६; १४. १, २६.
ज्ञातात् १९. १५, ६.
ज्ञातारम् ६. ३२, ३; ८. ८, २१.
ज्ञातिऽमुखाः १८. २, २८.
ज्ञातीन् १२. ९, ६.
ज्ञेषम् ९. ५, १६.
ज्मः २०. ८८, १.
ज्यया १. १, ३.
ज्या ५. १८, ८.
ज्याकाः २०. ९५, २; ३; ४.
ज्याके १. २, २.
ज्याऽघोषाः ५. २१, ९.
ज्याऽपाशैः ११. १२, २२.
ज्याम्ऽइव ४. ४, ७; ५. १३, ६; ६. ४२, १; १०१, ३.
ज्यायस्वन्तः ३. ३०, ५.
ज्यायान् ९. २, १९; २०; २१; २२; २३[३]; २४; १९. ६, ३.
ज्येष्ठः २०. ९२, १६; १०५, ४.
ज्येष्ठः १०. ८, २८; १८. १, १९.
ज्येष्ठऽघ्न्याम् ६. ११०, २.
ज्येष्ठतः ११. ४, १.
ज्येष्ठऽतातये ६. ३९, १.
ज्येष्ठम् ५. २, १; ९. १५, ४; १९. २२, २१; २३, ३०; ५३, ८; २०. ८०, १; १०७, ४.
ज्येष्ठम् ५. १, ८; ६. ११२, १; १०. ७, १७; २४; ८, १६; १९; २०; ११. ७, ५; २३; १०, ५; ६; १५. १, ३.
ज्येष्ठऽराजम् २०. ४४, ३.
ज्येष्ठऽवरः ११. १०, १; २.
ज्येष्ठस्य १२. २, ३५.
ज्येष्ठा १९. ७, ३.
ज्येष्ठाय १०. ७, ३२; ३३; ३४; ३६; ८, १.
ज्यैष्ठ्याय २०. ६९, ४.
ज्योक् १. ६, ३; १४, १; ३; ३१, ४; ४. २१, ३; ६. ६२, ३; १२. २, १८; ४९; १८. २, २९; १९. २४, २; ३.
ज्योतय ७. १७, १.
ज्योतय ४. ३७, १०.
ज्योतिः १. ९, २; ३५, ३; २. ११, ५; ४. १४, ३; १८, १; ५. १२, ७; १३, ३; ६. ९२, ३; ७. २३, १; ५५, ७; ८. १, ८; २१; २, २; ५, १७; ६, १४; ९. ५,

७; ११; २६; १०. १, १६; ११. १, २८; १२. १, १५; ३, ५०; १३. २, ९; ३६; ३, ११; १७; १६. २, ५; १८. १, ३५; ३, ६४; ६७; १९. १५, ४; २०. ११, ४; १५, ३; १६, ११; १७, ४; ८; ४६, १; ५८, ४; ६५, ३; ७७, ४; ७९, १; ९१, ४; १०.
ज्योतिःऽअग्राः १४. २, ३१.
ज्योतिःऽअनीकः १९. १०, ४.
ज्योतिःऽकृत् १३. २, १९; २०. ४७, १६.
ज्योतिषः ४. १, ५; १०, १; ६. ३६, १; २०. ८८, ४.
ज्योतिषा ८. ३, २१; २४; १०. २, ३१; ११. १, ३७; १३. १, ११; २, ४५; १६. ९, ३; १७. १, २७; २८; १८. ३, ७; २०. १६, ५; १७, ९; ६२, ७.
ज्योतिषाऽइव ४. १९, ३.
ज्योतिषि १. ९, १.
ज्योतिषीऽमान् १८. ४, १४.
ज्योतिषे ६. ६१, १.
ज्योतिष्मतः ९. ११, १४.
ज्योतिष्मती १९. ४०, ४.
ज्योतिष्मतीः ४. ३५, ५; १०. ५, ३८.
ज्योतिष्मन्तम् ९. ५, ६.
ज्योतिष्मान् १२. ३, ६; १६; १३. २, ३३; ३४; २०. १०७, १३.
ज्योतींषि ९. ५, ८; १०. ७, ४०; १०, १५; २०. ६१, २.

त

तंस्तनीहि ५. २०, १.
तक्मन् ५. २२, ६; ७; १२.
तक्मन् १. २५, १; २; ३; ५. २२, २; ५; ७; १०; ११.
तक्मनः ५. ३०, १६.
तक्मना ११. २, २६.
तक्मऽनाशन ५. ४, १.
तक्मऽनाशनम् ५. ४, २.
तक्मने १. २५, ४^{२}; ५. २२, ४; ८; ६. २०, १; २; ३.
तक्मा ४. ९, ८; ५. २२, ९; ११. २, २२; ६, ११; १२. ८, ४.
तक्मानम् ५. ४, १; ९; २२, १; ३; १३; १४; ९. १३, ६; १९. ३४, १०; ३९, १; ५; ६; ७; ८; १०.
तकः २०. ९२, १०.
तक्षकः ८. १४, १४.
तक्षत् २०. ३५, ६.
तक्षतम् ८. ४, ४.
तक्षती ९. १५, २१.
तक्षा १०. ६, ३.
तङ्गल्वाति ८. ६, २१.
तण्डुलः १०. ९, २६.
तण्डुलम् १२. ३, १८.
तण्डुलाः ११.१, १८; ३, ५; १२. ३, ३०.
तण्डुलैः १२. ३, २९.
तत् १. १६, २; १८, ३; २४, १; ३२, १; २; ३; ४; ३५, १; ३; २. १, १; २; ३, १; ३^{२}; ४^{२}; ५^{२}; ७, २; २५, ५; २८, २; ३०, ४^{२}; ३१, ५; ३. २, ४; ४, ५; ९, २; ३; १३, २; १५, ५; २२, १; ५; २३, १^{२}; ३०, ४; ४. १, ६; ७, ७; ८, ३; १०, ७^{२}; ११, ११; १२, २; १६, २; ५; १७, ६; ७; १८, ८; १९, ६^{२}; २०, १; ३७, ३; ४; ५; ५. १, ५; ७; २, १; ६; ४, १०; ६, २; ४; ८, २; ६; ११, ६; १०^{२}; १३, २; ९; १७, ९; १८, १४;

तर्पयन्ति ४. २७, ५.
तर्पयन्तु १५. ११, २; ५.
तर्पयन्तु ४. १५, १; ५; १८. ४, ३९.
तर्पयाति ९. ५, ९.
तर्पयामि २. २९, ६.
तर्हणम् ८. ४, ४.
तर्हणी २. ३१, १.
तर्हि ३. १३, ६; ११. १०, ५; १२. ४, १३; १६.
तलाशा ६. १५, ३.
तलीद्यम् ७. ८०, ३.
तल्प १२. २, ४९.
तल्पम् ५. १७, १२; १४. २, ३१.
तल्पा १३. १, १७.
तल्पानि १४. २, ४१.
तल्पेऽशयाः ४. ५, ३.
तव १. १०, २; २३, ३; २. २९, २; ३. १०, ८; ४. ९, ७; २५, ३; ३२, ५; ३९, १०; ५. ५, ८; ८, ९[2]; ३०, ८; ६. १५, १; ४४, १; ५१, ३; १३९, १; ७. १०, ३; ७७, १०; ८८, ३; ८. २, ३; ७; ९. ४, २३; ५, ३८; १३, ११; १९; १०. ४, १८; १०, १८; २०; २१; २२; ११. २, ९; १०[5]; ११; २४; ६, ९; ११, ७; ८; ९; १०; ११; १३; १४; २५; १२. १, १५; १४. १, ५१; २, ६०; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १८. १, १६; ३, २; ४, ६९; १९. १५, १; २०. ४, ३; ६, ४; ५; १३, ३; १५, ५; १८, २; २१, ३; १०[2]; २५, १; ३०, ५; ३३, ३; ३७, ५; ७; ६७, ५; ७४, २; ८७, ६; ९४, ५; १०६, १[2]; २; ११२, २; १२५, १.

तवःऽतरम् १९. २४, ७; २०. २६, १.
तवसः ४. ३२, ३.
तवसम् ११. १, १४; २०. ५४, १.
तवसे २०. १५, १; ३५, १.
तविषम् २०. ६१, ४; ६२, ८.
तविषस्य ४. ३२, ५; २०. ११, २.
तविषाः ४. १५, २; १९. ५८, ६.
तविषासः २०. ९४, ३.
तविषीभिः २०. ९, २; ४९, ५.
तविषीम् २०. ७३, ६.
तविष्यते १८. १, २३.
तवीयान् ४. ३२, ३.
तष्टा ११. १, २३.
तष्टाऽइव २०. ३५, ४.
तष्टानि २०. १२६, ५.
तसराणि १०. ७, ४४.
तस्करः ४. ३, २; २१, ३; १९. ४७, ७[2].
तस्करम् १९. ५०, ५.
तस्तभुः १४. ७, ४४.
तस्तम्भ ६. ८५, ३; ९. १४, ७; २०. ८८, १.
तस्तिरे १९. ४६, ३.
तस्तुवम् ५. १३, ११[3].
तस्तुवेन ५. १३, ११.
तस्थथुः १४. १, १४.
तस्थिऽवांसम् ४. ८, ७.
तस्थिषे ४. ९, २.
तस्थुः ९. १४, २; ३; १३. ३, १८; १४. २, ९; २०. ३३, ३.
तस्थुः ९. १४, १३.
तस्थुषः १३. २, ३५; २०. २६, ४; ४७, १०; ६९, ९; १०७, १४; १२१, १.
तस्थे ५. १७, ३; ९. १५, १९.

त॒स्थौ **४.** १, ३; ८, ३; **५.** १, ६; **९.** १४, १०; **१०.** ८, ३; ४०; ४२.

तस्मात् **३.** १३, १; २; ३; ४; २९, १; **४.** ९, ६; ३६, ७; ८; **६.** ५१, ३; ११४, १; ११५, १; २; १२०, १; १२१, २; **७.** ५, ४; ५७, १; ६६, १; २; **८.** २, १०; २३; २७; १२, २; ४; ६; ८; **९.** १, २४; ८, ७; १५, १०; **१०.** ५, २२; ६, ३; ८, २४; १०, १०; **११.** ७, ५; २३; १०, ३२; ३४; **१२.** २, ४०; ४, ९; १०; ४९; ५०; ७, ६; **१३.** १, १४; २५; ४८^{३}; ५५; ७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; **१४.** २, ५९; ६०; ६१; ६२; **१६.** ७, ११; ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१; **१९.** ६, १२^{३}; १३^{३}; १४; ३८, २; ४४, ८; ९; ४८, ३; ५३, ४.

तस्मिन् **३.** १५, ६; **४.** २८, ६; **५.** १७, १३; **९.** २, ३; ११, ७; ८; ९; १०; ११; **१०.** २, ३२^{२}; ६, ३५; ७, ३८; ४०; ८, ५; ९; ४३; **११.** ७, १; ८; २४; १०, ३४; **१२.** २, १७; ३, ६; ८; ३२; ३८; ५२; **१३.** १, ५८; **१८.** ३, ५३; ५४^{२}; **१९.** १७, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ४६, ३; ५३, ९; ७२, १; **२०.** ५५, ३.

तस्मै **१.** ५, ३; **२.** १२, ६; **३.** २३, ५; **४.** १, २; **५.** ७, २; ११, ११; १४, ६; २५, २; २८, ११; **६.** ५, ३; २०, ३; २७, १; २८, ३; ५५, १; ६३, २; ८४, ३; ८७, ३; १२८, ४; **७.** १८, ३; ९२, १; **९.** २, १९; २०; २१; २२; २३; २४; ३, १२; १५; १०, १; ४; ६; **१०.** २, २९; ६, ५; ७, ३२; ३३; ३४; ३६; ८, १; १५; **११.** २, २३; २७; ६, १८; १९; २३; **१२.** ४, १७; २३; **१३.** १, ५; **१५.** ३, ३; ४, १; ४; ७; १०; १३; १६; ५, १; ४; ६; ८; १०; १२; १४; **१६.** ६, ४; **१८.** ४, १४; ३७; ८३^{२}; ८४^{२}; **१९.** १७, १; २; ३; ४; ५; ७; ८; ९; १०; ५६, ३; **२०.** ३७, ९; ६८, १०; ६९, २; ७७, १; ८९, ५; ९७, १.

तस्य **१.** ५, २; २४, १; **२.** २७, ७; **३.** ७, ६; २२, ६; **४.** १, ५; २, ८; ८, १; २०, ३; २१, ४; २७, ६; २८, १; **५.** ५, ४; ८; ६, ३; ८, ३; १८, ५; **६.** ४, २; ६, ३; २४, ३; ३९, २; ७९, ३^{३}; १२२, ३; १२७, २; **७.** २१, ३; ८६, ५; ९७, १; **८.** ३, १०^{२}; १७; ७, २२; **९.** ४, ११; ५, २०; १४, १; ११; २१; १५, २४; **१०.** ५, ४५; ७, ४०; **११.** ३, १; ६, ९; **१२.** ३, ७; ४, २८; १०, १; २; ३; ४; **१३.** १, ५६; ५७; ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; ४, ८; १०; ६, ६; ७; ७, १२; **१४.** १, ३; २, ३३; ५०; **१५.** २, ४; १२; १८; २४; ३, १०; १५, १; ३; ४; ५; ६; ७; ८; ९; १६, १; २; ३; ४; ५; ६; ७; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; १८, १; **१६.** ७, १२; ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; **१८.** १, १६; ३, ४३; **१९.** ४९, ९;

५३, १; **२०.** ८, २; १७, ३; २५, ६; ९६, ३; १२५, ७.

तस्याः **३.** ११, १; **४.** ३९, २; ४; ६; **७.** २१, ६; **८.** १०, १; ११, ५; १३, २; ६; १०; १४; १४, २; ६; १०; १४; **९.** १, ५; १५, २१; **१०.** ८, ३१; **१२.** ४, ३३; ४४; ४६; ९, १; **१३.** १, ४२; **१५.** ३, ४; **२०.** ९६, ६.

तस्याम् **४.** १८, ३; **७.** ८५, १; **१०.** २, ३१; १०, ५; **१२.** ३, ९; **१४.** २, १४; **१५.** १३, १४.

तस्यै **१.** १३, ४; **५.** ७, ९; १०; **७.** ४८, २; **११.** २, १२; **१२.** १, २६; **१८.** ३, १.

ता **३.** १३, १; **५.** ११, ४; **९.** १४, १५; १५, १६; **१८.** १, ११; २, ६; **२०.** ३१, १; ३७, ६; १२६, २०.

ताः **१.** ४, २; ५, १; १८, ४; ३३, १; २; ३; ४; **२.** १४, ४; **३.** ४, ७; ७, ५; १३, ५; २३, ६; **४.** ५, ३; १७, ५; २१, ३; ४[३]; ३९, ८; **५.** १, ८; १८, १२; १९, ११; २८, १०[२]; २९, १४; **६.** २५, १; २; ३; ९१, ३; ९६, १; **७.** ४, १; २४, १; ५१, १; ७८, १; ११२, १; ११४, ३; ११६, १; ११७, १; १२०, ४; **८.** ५, ९; ७, ३; १०; १३; १७; २३; २४; ९, १५; १८; **९.** ५, ३८; ६, ५[२]; **१०.** ५, ३८[२]; ८, ३३; **११.** १, १०; ८, ९; १०, २८; ११, १५; **१२.** १, १६; ३१; २, ४१; ३, २५; २६[२]; २७; ४१; ४, ४३; ४७; **१३.** १, १०[२]; **१४.** १, ४५; २, ७; ३४[२]; ४५; ४९; **१५.** १५, ७; ९; १६, ७; **१८.** १, ११; २, ९; २०; ३, ६९[२]; ४, २६[२]; ४३[२]; **१९.** २, ५[२]; ८, ६; १३, ११; १७, ६[२]; २७, ३; ९; **२०.** ७१, १४; १०९, २; ३.

ताजद्भङ्गःऽइव **८.** ८, ३.

ताडंम् **१९.** ३२, २.

ताढि **७.** ८९, ३.

ताऽत् **१२.** १०, ४.

तादुरि **४.** १५, १४.

तान् **१.** ८, ४; ३०, ४; **२.** १२, ७; २५, ४; २६, १; ३४, ३; ४; **३.** १, ३; ५; २, ३; ६, २; ३; ८, ५; **४.** ४, ८; ११, १२; १६, ९; २२, १; ३६, १; ३; ९; **५.** ६, १०; ८, १; ७; १७, ७; १८, ११; २२, ७; २३, ५; **६.** २२, ३; ५०, ३; ७३, २; ८०, २; ९४, १; १०३, २[२]; ३[२]; १०४, २; ११३, २; **७.** १०२, ३; ११३, १; २; १२२, १; **८.** ४, ९; ६, ७; ८; १०; ११; १४; १५; २३; ९, २३; **९.** २, १७; १८; ५, २; ३०; १४, १५; १९[२]; **१०.** ३, ३; १६; ५, २१[२]; ७, २४; २७; ९, ६; **११.** १, ५; ७, ११; २२; १०, ३; ११, २२; २४; १२, २३; २४; **१२.** १, ५०; ५७; २, २४; ३, १६; १८; ३६; ४०; **१४.** २, १०; **१५.** १३, २; ४; ६; ८; १०; **१८.** २, १४; १६; १७; २८; ३४; ३५; **१९.** ६, १४; ८, ४; ३५, ३; ५; ४९, ७; ६५, १; ६६, १; **२०.** २४, ५; ३६, ८; ८७, ४; ११२, ३; १४३, ९.

तानय **४.** ४, ६; **६.** १०१, २.

तानि **१.** १८, १; **२.** १, २; **४.** १६, ५; **६.** ९६, ३; **७.** ५, १; ५८, ४; **८.** ९, १९; **९.** ३, ६; १४, १९; १५, २५; २७; **११.** ७, २६; **१२.** ६, ५; **१३.** १, ३९; **१४.** १, २८; **१५.** १७, ४; **१८.** १, १७; **१९.** २०, २; ३७, १; ४८, १; **२०.** ११, ७;

१२, २; २०, २; २१, ६; ३७, ५; ५७, ५; ६७, २.

तापर्यन् १९. २८, $२^{२}$.

ताबुर्वम् ५. १३, $१०^{३}$.

ताबुर्वेन ५. १३, १०.

ताभिः १. २२, ३; ४. २१, ३; ३७, ८; ९; ५. २२, १०; ६. ७७, ३; ७. ५०, २; ८. ३, ६; ९. २, २५; १३. १, ४; २, २४; १८. २, ८; १९. ३, २; ४, १; ९, १४; २०. ४७, २१.

ताभ्यः २. २, ४; ५; ९. ५, ३८; १९. १७, ६.

ताभ्याम् ४. ९, १०; १३, ७; ८. ३, २५; ११. २, १४; ४, $२^{२}$; $३^{२}$; $१३^{२}$; $१४^{२}$; $१५^{२}$; $१६^{२}$; $१७^{२}$; ११, ४; १८. २, १२; ५६; १९. ६८, १.

ताम् १. १४, ३; २. २५, १; ३५, १; ३. २, ६; १२, १; १७, ४; २५, २; ४. ४, १; ६, २; २०, ४; ३०, २; ३८, १; २; ४; ५. १४, ६; ७; १८, ७; २२, ६; ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ६. ३३, ३; ७८, १; ९०, १; १०८, ३; १०९, १; ११३, १; ३; १३६, १; १३७, १; ७. १६, १; ३९, ३; १२०, २; ८. ९, ७; ११, २; ३; १२, १; ३; ५; ७; १३, १; $३^{२}$; ४; ५; $७^{२}$; ८; ९; $११^{२}$; १३; $१५^{२}$; १४, १; $३^{२}$; ४; ५; $७^{२}$; ९; $११^{२}$; १२; १३; $१५^{२}$; ९. १, १; २०; १०. २, २९; ८, १०; १०, २३; ११. १०, ७; १२. ३, २१; ५४; ४, १४; २४; $४२^{२}$; ५, ५; १३. १, $२३^{२}$; १४. १, ५६; २, १३; ३८; ४८; ६५; ७४; १५. ३, ९; १८. ४, ३२; १९. ४, १; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; १९, $१^{३}$; $२^{३}$; $३^{३}$; $४^{३}$; $५^{३}$; $६^{३}$; $७^{३}$; $८^{३}$; $९^{३}$; $१०^{३}$; $११^{३}$; ४०, ४; ४८, ६; २०. १४३, २.

ताम्रऽधूम्राः १०. २, ११.

तायत् ४. १६, १; ७. ११३, १.

तायताम् १०. २, १७.

तायतेँ १०. ८, १०.

तायते १७. १, १८.

तायमाने १८. १, ४१; ४, ४५.

तायवः १३. २, १७; २०. ४७, १४.

तायादरम् ६. ७२, २.

तारका ५. १७, ४.

तारके इति २. ८, १; ३. ७, ४; ६. १२१, ३.

तारम् ४. ३७, ३.

तारयन्तः १८. ३, १०.

तारयन्ति ७. ११२, १.

तारिषत् २. ३, ६; ४. १०, ६; १२. २, १३; १४. २, ६७; १९. ३४, ४; २०. १३७, ३.

तारिषुः २. ७, ४.

तारीत् २. ७, ४; ६. १२४, ३; १२. ३, १७.

तार्क्ष्यम् ७. ९०, १.

तार्प्यम् १८. ४, ३१.

तार्ष्टऽअघीः ५. २९, १५.

तावत् ३. २२, ४; ५; ६. ७२, २; ३; ९. ९, २; ४; ६; ८; १२. १, ३३; ३, $२^{२}$; ४, २७.

तावतीः ८. ७, २५; २६.

तावन्तः १९. ६, ३.

तावान् ५. २२, ५; १३. ७, १६.

तासाम् १. २७, १; ३. २४, ६; ४. ८, ५; ३९, ८; ५. १, ६; १३, ९; ६. २१, $१^{२}$; ९०, २; ७. ३६, २; ४४, १; १२०, ३;

१०. १०, २८; ११. १, १३; ७, १३[२]; १२. ३, ४; ४, ४१; १३. १, ९.
तासु २. १०, ५; १२. १, १२; १९. १७, ६[२].
तिग्मऽआयुधौ ५. ६, ५; ६; ७.
तिग्मऽइषवः ४. ३१, १.
तिग्मः १३. २, ३२.
तिग्मऽतेजः ६. ६३, २.
तिग्मऽतेजसः १९. ९, १०.
तिग्मम् ४. २७, ७; ७. ८९, ३.
तिग्मऽशृङ्गः १३. १, २५; २०. ३७, १; १२६, १५.
तिग्महेती इति तिग्मऽहेती ५. ६, ५; ६; ७; ८. ३, २५.
तिग्मेन ६. ३४, २; ८. ३, २३; १३. १, ११.
तितिक्षन्ते ८. ६, १२.
तितिक्षुः १२. १, ४८.
तितृप्सात् ८. ३, १७.
तित्विषाणः २०. १३७, ९.
तित्विषे २०. १०७, २.
तिर २०. ६, ३.
तिर ६. ६, ३; ७. २७, ३; १२. २, ४५; १३. २, ३७.
तिरः ४. २०, ७; ६. ३४, ३; ७. ३९, ५; ८२, २; ८. १, ७; १४, १२; १२. २, २३; ३, ३९; १३. १, ३६; १८. १, १; १९. ४०, ४; २०. ३५, ७; १०२, १.
तिरःऽजनम् ७. ३९, ५.
तिरःऽधाम् ८. १४, ११; १२.
तिरःऽधे ८. १४, ९.
तिरतः १३. २, ३२.
तिरते १०. ७, ४२.
तिरश्चा २०. ३५, १२.
तिरश्चिऽराजयः १०. ४, १३; २०.
तिरश्चिऽराजये ६. ५६, २; १२. ३, ५६.
तिरश्चिऽराजिः ३. २७, २.
तिरश्चिऽराजिम् १०. ४, १७.
तिरश्चिऽराजेः ७. ५८, १.
तिरश्चीः ९. १३, १६; १०. २, ११.
तिरश्चीन् १९. १६, २; २७, १५.
तिरश्च्ये ३ इति १५. ३, ५.
तिरसे ७. ८६, २; १४. १, २४.
तिराति १८. ४, ४८.
तिरामसि २०. २०, ३; ५७, ६.
तिरामि २. ३१, ३; ६. १३१, १.
तिरीटिनः ८. ६, ७.
तिर्यक् १०. २, २४; २५.
तिर्यक्ऽबिलः १०. ८, ९.
तिर्यङ् १०. २, २८; ८, १९; ११. ६, २५.
तिर्यञ्चः १५. ३, ६.
तिर्यम् ४. ७, ३.
तिलः १८. ४, ३२.
तिलऽपिञ्ज्या २. ८, ३.
तिलम् ६. १४०, २.
तिलऽमिश्राः १८. ३, ६९; ४, २६; ४३.
तिलऽवत्साः १८. ४, ३३; ३४.
तिलस्य २. ८, ३.
तिलिपञ्जम् १२. २, ५४.
तिष्ठ १. १७, २[२]; ४. ७, ५.
तिष्ठ १. १७, २; २९, २; २. ६, २; १३, ४; ३४, ५; ३. १२, २; ४. ८, २; १२, ६[२]; १४, ९[२]; ५. ८, ९; ६. ८७, १; २; १२३, ५; ७. ७७, १०; १०. १, २०; ११. १, १४; ११, ५; ६; १२, ५; १२. ३, १; १३. २, ७; १४. १, ४७; २, १५; १९[२]; ३३; १८. २, ७; ३, ८; १९. १३,

५; ४६, ५; ६३, १; २०. ४९, ३; ७६, ८; ९२, १३.
तिष्ठः ८. १, ९; १०. १, २६.
तिष्ठत् २०. ९२, १२.
तिष्ठत १. १७, ४.
तिष्ठत ७. ७५, १; ११. ११, २; २६; १२, १; १२. २, २७; १८. २, २.
तिष्ठतः ६. १२७, २; ७. ११३, २; ९. २, २३; ११. १२, ११.
तिष्ठतः १०. ८, २; १५. ४, ३; ६; ९; १२; १५; १८; १९. ५४, ५.
तिष्ठतम् ११. ११, ३.
तिष्ठताम् १८. २, ३७.
तिष्ठति १. २, ४; १७, २; ४. १६, २; ६. १३८, ४; ७. २१, ६; १०. ८, ११; ११. २, २३.
तिष्ठति १०. ७, १[२]; ३[४]; ११. ७, ११; १२. ४, ३५; १५. ५, २; ५; ७; ९; ११; १३; १५; १९. ३९, ५; ६; ७; ८; २०. ७३, ४.
तिष्ठतु १. २, ४; १५, २; २. १४, ४; ५. ३०, १३; ६. १२३, ५; १०. १, १०; ११. ६, २४; १८. ३, ५१; १९. ४३, ७; ४६, २.
तिष्ठते ३. १५, ८; ११. २, १५; ६, ७; १९. ५५, १; ६.
तिष्ठते १९. ४९, २; ५३, ५.
तिष्ठथः २०. १४१, २.
तिष्ठध्वम् ८. ४, १८; ११. ११, २६.
तिष्ठन् ४. ५, ५; ७. १०७, १; ९. १२, २०[२]; २१[२]; १२. २, ४९.
तिष्ठन्तः ७. ६२, २; १२. १, २८.
तिष्ठन्तम् ८. ३, ५; १०. ७, ४१; ११. १, ३६.
तिष्ठन्ताम् १४. २, २५.
तिष्ठन्ति ४. १६, ६; १०. ७, १२; १६; १२. १, २७.
तिष्ठन्ति ८. ९, १९; ९. १२, २६; १५, १७; १३. ४, ६; १४. १, १; १८. १, ९; १९. ५८, ३.
तिष्ठन्तीः २०. ९१, ४.
तिष्ठन्तु १. १७, १.
तिष्ठन्तु ४. ३४, ५; ६; ७; १०. ५, ६; १८. ४, ३३.
तिष्ठसि ५. ५, ५; ९. ३, १७; १४. १, ५; १५. ३, १.
तिष्ठसे १७. १, १६; १९. ४७, १.
तिष्ठात् १. १७, २; ६. ४४, १.
तिष्ठाति ३. १२, १; ६. ५३, २.
तिष्ठाथः २०. १४०, ३.
तिष्ठामि ६. ४२, ३.
तिष्ठासि १९. ४५, ४.
तिष्ठे ४. ३०, ७; ९. १, २४.
तिसृऽभिः २. १२, ४; ७. ४, १.
तिस्तिरे २०. २३, २.
तिस्रः ३. २४, ६; ४. २०, २[२]; ५. ३, ७; १२, ८; १५, ३; २७, ९; २८, १०; ६. २१, १; ७५, ३[२]; १००, १; ७. ४४, १; ८. ४, ११; ९, १३; ९. १४, १०; १५, ३; १०. ८, ३; १०, २८; ११. ७, ३; १३. ३, २१[३]; १९. २७, ३[२]; ३२, ४[२]; २०. ९१, ४.
तीक्ष्णऽइषवः ३. १९, ७; ५. १८, ९.
तीक्ष्णः १९. ३३, ४.
तीक्ष्णऽतराः ३. १९, ४.
तीक्ष्णऽशृङ्गाः १९. ५०, २.
तीक्ष्णऽशृङ्गी ४. ३७, ६.

तीक्ष्णऽशृङ्गयः ८. ७, ९.
तीक्ष्णीयांसः ३. १९, ४^{2}.
तीक्ष्णेन ८. ३, ९; १२. ११, ५.
तीतपासि ६. ३२, १.
तीर्त्वा ९. ५, १; ३.
तीर्थम् १४. २, ६.
तीर्थैः १८. ४, ७.
तीर्यतीः १९. ९, ८.
तीव्रः ३. १३, ५; १८. १, ४८.
तीव्रस्य २०. ९६, १.
तीव्राः १०. २, ११; २०. ८९, ८.
तीव्रान् २०. ८९, ५.
तीव्रैः २०. १७, ६.
तु ४. १८, ६; १९. ३१, ४; २०. १४, ४; १८, ४; २३, १; ६२, ४; ६८, ११; ७४, १; २; ३; ४; ५; ६; ७; ९२, १३.
तुग्र्यऽवृधम् २०. १०५, ३.
तुजः २०. ११, ५.
तुजता २०. ३५, ६.
तुजन् २०. ३५, ६.
तुजयत्ऽभिः ८. ४, ७.
तुजये ७. ५१, १.
तुजे ६. ३३, १.
तुजेते इति २०. ३५, १४.
तुञ्जते २०. ७२, १.
तुञ्जेऽतुञ्जे २०. ७०, १३.
तुण्डिकः ८. ६, ५.
तुण्डेलम् ८. ६, १७.
तुदत् २०. ३०, ४.
तुदतु ३. २५, १.
तुदन्तु ३. १७, ५.
तुन्दाना ६. २२, ३.
तुन्ना ६. २२, ३.

तुभ्यं २०. २४, ८; ७३, १.
तुभ्यम् १. १३, ३; २. ९, ५; २८, १; ३. २३, ५; ४. ८, २; ५. १८, १; ६. ९२, ३; ११२, १; ७. ४८, ३; ८७, ३; ६; ८. १, ५^{2}; २, २२; ७, २५; ९. ५, ३८; ११. २, २४^{2}; ६, १९; १२. १, ६२; १४. १, ५८; २, १; १७. १, १८^{2}; १९. ४८, २; ५०, ७; २०. २५, ७; ३३, १; २; ३७, १०; ६७, ६^{2}; ७३, १; ८८, ३; ९६, १; २^{2}.
तुभ्रम् २०. ३६, ५.
तुरः ५. २, ८; २०. १०७, ११.
तुरः ३. १६, २; ६. १०२, ३; २०. ५०, १.
तुरःऽपेये २०. ३१, ३.
तुरऽगातु ९. १५, ८.
तुरण्यवः २०. ११९, २.
तुरयन्तम् २०. १०५, २.
तुरस्य २०. ३५, १३.
तुरा २०. ३१, २.
तुराणाम् ७. ५२, २.
तुराय २०. ३५, १.
तुराषाट् २. ५, ३; २०. १२, ७.
तुरीपम् ५. २७, १०.
तुरीयः १. १६, १; ३१, ३; १४. २, ३.
तुरीयम् १०. १०, २९^{4}.
तुरीयम् ९. १५, २७; २०. ९१, १.
तुरीया ८. ९, १४.
तुरीयेण ७. १, १.
तुरेण १८. ३, ४८.
तुर्मिशम् १९. ७, १.
तुर्वणिः २०. ३५, ११.
तुर्वणे २०. १४१, ३.
तुर्वशम् २०. ३७, ८.

तुर्वशे २०. १२०, १; १४१, ४.
तुर्वीतये २०. ३५, ११.
तुविऽकूर्मिम् २०. ३६, ५.
तुविऽक्षत्राम् ७. ६, २.
तुविऽग्राभम् २०. ३६, ५.
तुविऽग्रीवः २०. ५, २.
तुविऽजात २०. ७६, ५.
तुविऽजातः २०. ८८, ४.
तुविऽतमः ६. ३३, ३.
तुविऽद्युम्न २०. ७१, १२.
तुविऽद्युम्नस्य २०. १०४, ४.
तुविऽप्रतिम् २०. २६, ३.
तुविऽमघ २०. ६०, २; ७४, १; २; ३; ४; ५; ६; ७.
तुविऽराधसम् २०. १२, ५.
तुविऽवाजाः २०. १२२, १.
तुविऽशुष्मः २०. ९५, १.
तुविष्मान् २०. ३४, १३; ९४, १.
तुषम् १२. ३, १९.
तुषाः ९. ६, १६; ११. ३, ५.
तुषान् ११. १, २९.
तुषैः ११. १, १२.
तुस्तुवुः २०. ११५, ३[२].
तूर्तुजानः २०. ३५, १२; ८४, ३.
तूतुजानः २०. ९४, १.
तूपराः ११. ११, २२.
तूर्यम् ५. १२, ८; १८. १, ९; २०. ३६, ११.
तूर्य २०. १०५, १.
तूर्वयाणम् २०. २१, १०.
तूर्वसि २०. १०५, २.
तूलम् १९. ३२, ३.
तृचेभ्यः १९. २३, १९.
तृड्ढा १९. ३६, ५.
तृणद्मि १९. ३२, ४.
तृणम् २. ३०, १; ३. १२, ५; ६. ५४, १; १०२, २; ७. ७७, ११; ९. १५, २०.
तृणस्य ९. ३, ४.
तृणहान् ५. ८, ७.
तृणा ११. ९, २१.
तृणानि ९. १२, २२.
तृणेढु ८. ८, ११.
तृणैः ९. ३, १७.
तृतम् १७. १, १५.
तृतीयः ४. १६, २; ९. १४, १; १०. ४, १; १३. ५, ३; १४. २, ३; १५. १५, ५; १६, ३; १७, ३.
तृतीयकम् ५. २२, १३.
तृतीयकम् १९. ३९, १०.
तृतीयकाय १. २५, ४.
तृतीयम् ६. ४७, ३; ९. ५, १; ३; ६; ११; १०. १०, ८.
तृतीयस्याम् ५. ४, ३; ६. ९५, १; १९. ३९, ६.
तृतीया १८. २, ४८.
तृतीयाम् १५. १३, ५.
तृतीये ६. ११७, ३; १२२, ४; ९. १, १३; ५, ४; ८; १३. १, ११; १८. ४, ३.
तृतीयेन ७. १, १; १८. ३, ७.
तृतीयेभ्यः १९. २२, १०.
तृन्द्ध १९. २९, २[४].
तृन्द्धि ५. २९, ४.
तृन्धि २०. ८, १.
तृपत् २०. ६७, ६; ९५, १.
तृष्णवः २०. २४, २.
तृष्णुहि २०. ६७, ५.

तृप्तः १०. ८, ४४.
तृप्त्यां ९. ५, ९.
तृप्यतु ११. ११, १०.
तृप्यते १९. २, ५.
तृप्यन्तु ११. ११, ९.
तृप्रऽदंशिनः ७. ७८, ३.
तृम्प २०. २२, १.
तृषत् २. २९, ४.
तृषाणः २०. ५२, २; ५७, १५.
तृष्टऽजम्भाः ६. ५०, ३.
तृष्टऽदंश्मा १२. १, ४६.
तृष्टऽधूमम् १९. ४७, ८; ५०, १.
तृष्टम् ५. १९, ५; ८. ३, १२; १०. ५, ४८; १४. १, २९.
तृष्टऽवन्दने ७. ११८, १.
तृष्टा ५. १८, ३; ७. ११८, २.
तृष्टानाम् १९. ५७, ३.
तृष्टिका ७. ११८, २.
तृष्टिके ७. ११८, १.
तृष्टिके ७. ११८, १.
तृष्णया ३. ३१, ३.
तृष्णाः ११. १०, २१.
तृष्णाऽमारम् ४. १७, ६; ७.
तृह्यन्ताम् १. २८, ४.
तृह्यन्ते ५. १७, ७.
तृह्यमाणानाम् १०. ४, १८.
ते १. ७, ५; ३०, ३; ३१, २; ३५, ४; २. १२, १; ३२, ५; ३. ३, ५; ६, ७; १५, २; २१, १०; २२, २; २६, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ४. ६, ७; ९, ८; २७, १; २; ३; ४; ५; ६; ७; ३०, ४; ३५, ७; ३६, ६; ४०, १; २; ३; ४; ५; ६; ७; ८; ५. ३, १०; ६, ३; १७, १; १८, १०; १९, ३; २३, ४; १२; २४, ६; १५; १६; १७; २८, ३; ३०, १५; ६. २२, १; ४७, ३; ९३, १; ११८, ३; ७. ५, १; १३, २; २९, १; ३५, १; ५५, ४; ६२, २; ३; ७३, २; ८२, ३; ८५, ४; ११४, ७; ८. १, १४[२]; २, २१; ४, २४; ५, ५; ६; १३, १२; ९. १, ९[२]; २, १०; १२; ३, ३; ४, १६; ५, २९; ६, १०; १४; १५; ११, ३; १५, १; १७[२]; १८; २२; १०. २, ४; ३, ९; ५, ३९[२]; ४१[२]; ७, १७[२]; ८, १७; ३५; ९, ७; ९; १०, ५; ३१; ३२; ११. १, १; ३; ७, २०; २१; ८, १; २; ३; ४; ५; ६; ८; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; १०, २[२]; ४; ५; ६; १०[२]; १३; २६; १२, २; १२. १, ४९; २, १४; ५०; ५१; ३, ४९; १३. १, ३२; २, २७; ३, ९; १४. २, ७३; १५. १५, ८; १७, ५; ६; १६. ६, ७; १८. १, ३; ४४; ४५; ४७; ५१; २, ३५; ४७; ५५; ३, १९; ४२; ४३; ४५[२]; ५१; ६८; ४, २५; २९[२]; ४०; ४२; ४४; ६५; ८६; ८७; १९. १८, १; २; ४; ५; ६; ७; ९; १०; २०, ३; २७, ११; १२; १३; ४८, ५[२]; २०. १२, ५; १५, ४; २१, ६[२]; ७५, ३; ९१, ८; ९४, ६.
ते १. ३, १[३]; २[३]; ३[३]; ४[३]; ५[३]; ६; ७[२]; ८[२]; ९; ७, ५; १०, २; ११, १; ५; १३, १[३]; २; ३[२]; ४; १४, २; ३[२]; ४[२]; १८, ३; २२, १; ४[२]; २३, ३; २४, ३[२]; २५, १; २; ३५, १; २. २, १[२]; ३, १; २; ६, २[२]; ८, ३; ४; ९, ४[२]; १०, १; २[२]; ३[३]; ४; ५; ६; ७; ८; १२, ७; ८; १३, ४[२]; ५; १९, १; २; ३; ४; ५; २०, १; २; ३;

४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २९, ६; ७[३]; ३०, १; ३२, ६[३]; ३३, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ३५, ४; ३६, ८; **३.** १, ४; ३, ४; ६; ४, ५; ७; ७, ३; ११, ४; ८; १२, ६; १५, ८[२]; १८, ३; ६[३]; २०, १; २२, ४; २३, २[२]; ५[२]; २४, ७; २९, ७; **४.** ३, ३[२]; ६; ४, ३[२]; ७; ६, ४; ६[३]; ८; ७, १; ४; ९, १०; १०, ७; १२, २[३]; ३[३]; ४; ५; १३, २; ५[२]; १६, ६; ७; ९; १७, ४; ८; १८, ५; १९, ५; ८; २२, ५; ६[२]; ३०, ४; ३१, ३; ५; ३२, १; ६; ७; ३३, ४[२]; ३८, ६[३]; ३९, ९; **५.** १, ३; ५; ८; २, २; ५[२]; ४, ९; ५, १; ७; ६, ९; ७, २; ७; ८, ५; ११, ६; ८; ९; १०[२]; १३, १[२]; २[४]; ३[२]; ४[२]; १८, १; १९, १२; १३; १४; २०, २[२]; ७; २२, १०; २५, २; ३; ४[३]; ५; ९[२]; २८, ५; ६; ७; २९, ११; १४; ३०, १[३]; २; ३; ४; ५[२]; ९; १०; ११; १५; ३१, १; २[२]; ३; ४[२]; ५; ६; ७; ८; ९; **६.** ८, २; ३; ९, १; १२, १; २; १३, १; २[४]; ३[३]; १६, १[२]; २[२]; १७, १; २; ३; ४; १८, १; ३[२]; २०, ३; २९, २; ३०, २; ३९, २; ४२, १; २[२]; ३; ४३, ३[२]; ४४, २; ४६, १; २; ४९, १; ५६, ३[३]; ६३, १[२]; २; ७०, १; २; ३; ७२, १; २; ३; ७७, ३[२]; ७९, ३; ८०, १; ३[४]; ८२, ३; ८४, १; २; ८५, २; ३; ८८, २[२]; ३; ८९, १; २[३]; ९०, १; २[२]; ३; ९१, १; २; ३; ९२, १; २; ३; ९८, २; ३; १०१, ३; १०२, १; २[२]; १०६, १; १११, १; २[२]; ११२, ३; ११३, १; ३; १२५, १; १२६, १; १२७, २; १२८, ४; १३१, १; १३२,

१; २; ३; ४; ५; १३६, ३; १३७, २; ३; १३८, ४[२]; ५; १३९, १; २; १४२, ३; **७.** ९, १; १०, ३; ११, १; १२, १; १३, २[२]; २१, ४; ६; ३६, २[२]; ३[२]; ३९, २; ४४, १[२]; ५०, २; ५२, ५; ५५, २[२]; ३[२]; ६[२]; ५७, २; ५८, ३; ६; ८[२]; ६६, २; ७०, १; २[२]; ७१, १; ७३, ४[२]; ५[२]; ७८, ३[३]; ८१, १; ८३, १; ८४, १; ४; ८५, ३; ८७, ३; ६[२]; ८८, १; ९५, २; १०२, ६; ११२, १; ११६, १[२]; ११९, १[४]; १२३, १[२]; **८.** १, १; ३[२]; ५; ६[२]; ७; ८; १०; १५; २०[२]; २१; २, १[२]; २; ३[२]; ४[२]; ९; १०; ११; १३[३]; १४[३]; १५; १६[३]; १८; १९; २१; २६; ३, ११; १८; १९; २५; ४, १४; ५, २२; ६, १; १८[२]; २०; ७, ३; ४; ८, ७; **९.** १, १०; २०; २, ५; १६; १९; २०; २१; २२; २३; २४; २५; ३, २; ४[२]; ६[२]; १०; १२; १३; १४; १५; १८; ४, ६; १०[३]; ५, ३७; ३८; १३, १; २[२]; ३; ४; ५; ७; ९; १२; १६; २१; २२; **१०.** १, ४; ८[३]; ११; १६[२]; १८; २०; २१; ३, २; ३; ४; ४, २१; २२; २४; २५; ५, ४५; ७, २१; २५; ९, २[२]; ३; ७[२]; १३[३]; १४[२]; १५; १६[२]; १७[२]; १८; १९[२]; २०; २१[२]; २२[३]; २३[२]; २४; २५; १०, १[३]; ७[२]; १०; ११; २०; **११.** १, ६; १०[२]; ११[२]; १९; २०; २५; ३२; २, २[२]; ३[३]; ४[२]; ५[३]; ६[३]; ९; ११; १५[३]; १९; २५[२]; ३१[३]; ४, १; ४; ५; ६; १३; ६, २[४]; ७[३]; ८[४]; ९[२]; १८; २३; **१२.** १, ११[२]; १२[२]; १८; २३; २४; २५; ३१[२]; ३३; ३५[३]; ३६[२]; ४६; ४७; ५६; ६१[२]; ६२; २, १[२]; ३; १४; २१[२]; ५३[२]; ३, १; २२; ५४; ४,

४५; ५२; **१३.** १, ५[३]; ८; ९[२]; १०; १४; ३५; ३७; ४४[३]; ५६; ५७; २, ३; ६[२]; ७; २९; ३७; ३, १०; २१; ७, १६[२]; १७; ८, ३; ५; ६; ९, १; २; ४; **१४.** १, ५; ११[२]; १२; १६; १९; २१; ४०[२]; ४७[२]; ४८; ४९; ५०; ५१; २, ३[३]; ९; २४; ३३; ३४[२]; ३५; ५९; ६१; ६२; ७५; **१५.** ११, २[३]; ६; ८; १०; **१६.** ५, १; ४; ५; ६; ७; ८; **१७.** १, ८; ११; १२; १३[२]; **१८.** १, २; ३; १३[३]; १४; १५; २४; ३२; ४०; ५४; ५९; २, ७; ८[३]; ९; १०; १२; २०; २१; २३; २४[३]; २६[३]; ३०[२]; ३६; ५६; ५७; ३, ४; ७[२]; ९; २४; ४५; ५२[३]; ५५; ६०[२]; ६८[२]; ६९[३]; ७१; ७२; ४, ९; १५[२]; २५[२]; २६[३]; ३१; ३३; ३४; ४२[३]; ४३[३]; ४४; ५२; ५६; ५९; ६६; ७५; ७६; ७७; ८८; **१९.** २, १[४]; २[३]; ५; ३, २; ३[३]; ४, १; ८, ५; ११, ५; १५, ४; १८, ३; ८; २६, ४[२]; २७, ४; २८, १; ३०, १[२]; २[२]; ४; ३२, १; ३; ३३, ४; ३४, ८; ९; ३९, २; ३[२]; ४२, ४; ४४, २; ४५, ३; ४[३]; ४६, १; ४७, २; ३[२]; ५[२]; ४८, १; ४; ६; ५०, २; ५२, ५; ५५, १; २[३]; ६; ५६, ६[२]; ६४, ३; ४; ६६, १; **२०.** ३, १; ४, २; ३[२]; ५, ४; ५; ६; ७; ९, ४; ११, २; १२, ४; १५, २; ४; ५[३]; १७, २; ५; १९, २; ३; २०, २[२]; ३; ४; २१, ११; २४, १; ६; ८; २५, ३; २६, ३; २७, ३; ४; ६; २८, ४; ३०, १[२]; ३२, ३; ३४, १८; ३५, १६; ३६, ४[२]; ३७, ६[२]; ७; ८; ९[२]; ३८, १; ३९, ५; ४३, ३; ४५, १; २; ४७, ७; ४९, ७; ५६, २; ६; ५७, ३; ५[२]; ६; ७; ५८, ३; ६०, १; ५; ६१, १; ३; ६२, ७; ६४, ५; ६७, ६; ६८, ३; ४; ६९, ५; ७१, ५; १०; ११; ७३, २[२]; ७५, २; ३; ७६, २; ३; ५; ६[२]; ७७, ७; ८; ८१, १; ८५, ३; ८६, १; ८७, ३; ६; ८८, ३; ९२, ९; २०; ९४, २[२]; ९[२]; ९५, ४; ९६, ५; ९; १०[२]; ११; १२; १३[२]; १४; १५; १६; १७[२]; १८[२]; १९[२]; २०[२]; २१[२]; २२[२]; २३[२]; १०५, २[२]; १०७, ५; ८[२]; १०८, २; ११२, १; ११३, २; ११४, २; ११६, २; ११७, १; २; ३; १२६, १३; १५[२].

ते इति॑ **४.** २६, १; २; ३; ४; ५; ६; ७; **५.** २४, ३; **६.** १३८, ४; **१०.** ८, १२; २०; **११.** ७, ८; ९; **१५.** १०, ३; **२०.** ३५, ८.

तेज॑ः **१.** ३५, ३; **२.** १९, ५; २०, ५; २१, ५; २२, ५; २३, ५; **५.** १९, ४; **७.** ९४, ४[२]; **९.** १, १७; **१०.** ३, १७; ४, २५; ५, ३६; **१२.** ३, २; ६, १; **१३.** ३, ५; **१४.** २, ५४; **१६.** ८, १; ४; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२]; १९[२]; २०[२]; २१[२]; २२[२]; २३[२]; २४[२]; २५[२]; २६[२]; २७[२]; २८[२]; २९[२]; ३०; ३३; **१९.** ३१, १२[२]; ५३, ४.

तेज॑ःऽभिः **१३.** १, ३०.

तेज॑नम् **१.** २, ४; **६.** ४९, १.

तेज॑सः **१९.** ३४, २.

तेज॑सा **३.** ५, ८; **५.** २८, १३; **९.** २, १५; **१०.** ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; ६, २७; ३०; **१३.** ८, ४; ५; ६; ९, १; २; ५; **१९.** ३१, ३; ३६, १.

तेज॑से **१९.** २८, १; ४५, ६; ७; ८; ९; १०.

तेजस्वत् **१८.** ३, ७१.

तेजांसि **७.** १४, १; **१३.** १, १४.

तेजिष्ठया **२०.** २१, ८.

तेन **१.** ३, १; २; ३; ४; ५; ९, ३; २२, १; २९, १; **२.** ७, ३; ५; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; **३.** ५, ८; ६, ४; ७, ३; १०, १२; १४, १; १६, ५; १७, ७; २२, ३; **४.** ५, १; ७, १; ११, ६; १४, १^{2}; ६; १७, ८; १८, ३; २०, ८; ३५, १; २; ३; ४; ५; ६; ३६, ५; **५.** ६, ११; १२; १३; १४; १७, ५; २८, १२; १३; **६.** ७, १; २; ३; १२, १; २; २४, ३; ५७, २; ६८, ३; ७४, २; ७८, १; ८०, १; ३; ८२, २; ३; ९१, १; ९२, २; १००, २; १०१, १; २; १२९, २; ३; **७.** २१, ४; ३९, २; ७३, ४; ५; ८४, १; ८६, ६; **८.** ७, ५; ८, ५; ६; ७; ८; **९.** २, १६; १७; ३, १५^{2}; ४, १३; २४; ५, १७; १८; २४; ६, ९; ७, २; १५, १९; **१०.** १, ९; १५; ३, १; ५, १५; १६; १७; १८; १९; २०; ६, ६; ७; ८; ९^{2}; १०; ११; १२^{2}; १३^{2}; १४; १५; १६; १७; २०; २१; **११.** १, ३७; २, ७; ४, १^{2}; ४^{2}; ८^{2}; ९^{2}; १०^{2}; ११^{2}; १२^{2}; ७, १२; १२, १३; **१२.** १, २३; २४; २५; ४६; ४७; २, १; २; ४७^{2}; ३, १५; २२; **१३.** १, ७^{4}; २, १५; **१४.** १, ३५; ३६; ४८; ५३; ५५; २, ५३; ५४; ५५; ५६; ५७; ५८; **१५.** १, ३; ११, ३; ४; ५; ६; ८; १०; १३, २; ४; ६; ८; १०; **१६.** १, ५; ७, १; १२; **१८.** १, ९; ५३; २, ३०; ३, ५६; **१९.** ६, ११; ९, ४; २२, २१; २३, ३०; २४, १; २७, १०; ३०, १; ३२, ७; १०; ३९, ९; ४७, ८; ५०, १; ५३, ९^{2}; ७२, १; **२०.** ८९, ७; १३९, ५; १४१, ५.

तेनो इति **९.** १, २०; **१८.** ३, १९.

तेभिः **१.** १५, ३; ४; **२.** ३५, २; **५.** ८, २; १८, ८; **७.** ५७, २; ७०, २; **११.** ११, ६; **१८.** ३, ४६; ४, २; ३; **१९.** ४७, ५; ५०, २; **२०.** ३३, १.

तेभ्यः **३.** २१, १; २; ३; ४; ५; ६; ७; २६, १^{2}; २^{2}; ३^{2}; ४^{2}; ५^{2}; ६^{2}; २७, १; २; ३; ४; ५; ६; **४.** ३९, १०; **६.** १३, १; **७.** ११४, ६; **८.** १, १४^{2}; ८, १०; **१०.** ४, २३; ९, १२; **११.** १, ४; **१२.** ४, २६; **१४.** २, ४६; **१८.** २, २९; ४९; ३, ५९; ७२; ४, ५७.

तेषाम् **१.** १, १; **२.** ३, २; ३५, १; **३.** ९, ६; १०, ६; २६, १; २; ३; ४; ५; ६; **४.** ५, ५; **५.** १९, २; **६.** १५, २; ५५, १; ३; ६५, १; ६७, २; ११६, ३; **७.** ८, १; **८.** ३, १५; ६, २४; **९.** २, ४; ९; ७, ४; ११, ४; १४, १६; **१०.** ४, १८^{2}; **११.** ५, ४; ११, २६; **१२.** ३, ६; ४, ११; २०; **१८.** १, ५८; ६८; ८६; ८७; **२०.** ३७, १०; ५६, ६.

तेषु **८.** ९, १९; **१२.** १, ५६; ४, २६; **१७.** १, ७.

तैः **३.** २३, ४; **४.** १६, ९; ३६, ५; **५.** २१, ८; **८.** ८, ९; **१०.** ५, २१; ६, २०; **११.** ४, ६^{2}; ७^{2}; ७, १४; **१३.** १, ३५; **१९.** ९, ५; १२.

तैमातस्य **५.** १३, ६; १८, ४.

तोकम् १. २८, ३; ४. १७, ३.
तोकस्य २०. ७१, २.
तोकानि ५. १९, २.
तोकाय २०. १४१, १.
तोकेभ्यः १. १३, २; २६, ४.
तोशमाना ३. १७, ९.
तौ ३. २४, ७; ४. २५, १; २; ३; ४; ५; ६; ७; २८, १; २; ३; ४; ५; ६; ७; २९, १; २; ३; ४; ५; ६; ७; ५. २४, ५; ३०, १०; ६. १४०, १; ७. ५९, ३; ८. ९, १[२]; ९. १, ७[२]; ३, ९; ५, २७; ६, १२; १०. ४, ८; ९, २५; ११. ७, १०; १२. २, ३२; १४. २, ७१; १८. २, १३; १९. १३, १; ४४, १०.
तौर्दी १०. ४, २४.
तौलस्य १. ७, २.
तौविलिके ६. १६, ३.
त्मना ५. २७, ११; ७. ५०, १; २०. १६, ७; १२२, २.
त्मन्या ५. १२, १०.
त्यजसम् १८. १, ३.
त्यत् २०. १६, ७; ३५, १५; ३७, २; १०६, १; १३७, १०; ११.
त्यम् ७. १५, १; ९०, १; १३. २, १६; १८. १, २१; २०. ३५, ३; ३६, ६; ४७, १३.
त्यस्यै २०. १२६, २३.
त्याः २०. ७४, ४.
त्ये ८. ३, १९; ४, २०; १३. २, १७; २०. १०, १; ४७, १४; ५९, १.
त्रपु ११. ३, ८.
त्रयः ४. ३, १; ९, ८; ५. २८, ३; ८; ६. ८०, २; ११२, २; ८. ९, १३; ९. १५, २६; १०. ६, ३१; ११. १, १०; ३, २०; १२. ३, २०; १३. ३, ६; १८. ४, ४; १९. ४७, ४.
त्रयःऽत्रिंशत् ६. १३९, १; १०. ७, १३; २३; २७[२]; ११. ७, २; १२. ३, १६; १९. २७, १०; ३७, १.
त्रयःऽत्रिंशतम् ११. ५, ३.
त्रयःऽत्रिंशासः १९. ५६, ३.
त्रयःऽत्रिंशेन ८. ९, २०.
त्रयःऽदश ३. २१, ५.
त्रयःऽदशः ५. ६, ४.
त्रयःऽदशम् १३. ३, ८.
त्रयान् ४. ११, २.
त्रयोदशऽऋचेभ्यः १९. २३, १०.
त्रसत ८. ८, १९.
त्रसदस्युम् २०. ३७, ३.
त्रसन्तु ५. २१, ८.
त्राता ४. १९, ३; १९. १५, ३.
त्रातारम् ७. ९१, १.
त्रातुः ६. ९९, ३.
त्रामऽभिः २०. २१, १०.
त्रायताम् ६. ९९, ३.
त्रायताम् ८. ५, १९.
त्रायध्वम् ६. ९३, ३.
त्रायन्ताम् ४. १३, ४[३]; ८. ७, २; ११.
त्रायमाणः ८. १, १५; ७, १४; १९. १०, १०; ३९, १.
त्रायमाणम् ४. ९, १; ६. ४, १.
त्रायमाणाम् ८. २, ६.
त्रायमाणायै ६. १०७, १.
त्रायमाणे ६. १०७, १; २.
त्रायसे ५. ५, २.
त्रायस्व २०. ३७, ७.

त्रायस्व १९. ४४, ४; ४९, ३.
त्रासयं ५. २१, ५.
त्रासय ५. २१, ४; ६.
त्रिऽअरे १०. २, ३२.
त्रिऽआयुषम् ५. २८, ७^{२}.
त्रिंशत् ५. १५, ३; ६. ३१, ३; १९. ४७, ४; २०. ४८, ६.
त्रिंशत्ऽअङ्गम् १३. ३, ८.
त्रिंशतम् २०. १३, ४.
त्रिंशत्ऽअराः ४. ३५, ४.
त्रिंशता ७. ४, १.
त्रिः ५. २, ३; ८. ३, ११; १२. २, २९; १४. १, ४१; १९. ६, १५; ३४, ६; ३९, ५^{३}; २०. ९२, ४; १०७, ६.
त्रिऽककुत् ४. ९, ८.
त्रिऽककुदम् ५. २३, ९.
त्रिऽकद्रुकेभिः १८. २, ६.
त्रिऽकद्रुकेषु २. ५, ७; २०. ९५, १; ११०, ३.
त्रिऽचक्रेण १४. १, १४.
त्रितः ५. १, १; ६. ११३, १.
त्रितस्य ६. ११३, ३.
त्रिते ६. ११३, १; १९. ५६, ४; २०. १११, १.
त्रिऽदिवम् १०. ९, ५; १०, ३२; १७. १, १०.
त्रिऽदिवे ९. ५, १०.
त्रिऽधातु २०. ८३, १.
त्रिऽनाके ९. ५, १०.
त्रिऽनाभि ९. १४, २; १३. ३, १८.
त्रिऽनामन् ६. ७४, ३.
त्रिऽपञ्चाशीः १९. ३४, २.
त्रिऽपात् ९. १५, १९; १९. ६, ३.
त्रिऽपादम् १३. २, २७; ३, २५.
त्रिऽपृष्ठे ९. ५, १०.
त्रिऽप्रतिस्थिते १०. २, ३२.
त्रिऽभिः ६. ११२, २; १०. ८, ४३; १२. ३, ४२; १९. ६, २.
त्रिऽभुजम् ८. ९, २.
त्रिऽयोजनम् ६. १३१, ३.
त्रिऽवरूथम् ७. ७, २; ८. ५, २०; ९. २, १६; २०. ८३, १.
त्रिऽवृत् ५. २८, ४; ६; ११.
त्रिऽवृतः १९. २७, ३.
त्रिऽवृतम् ८. ९, २०; १०. ८, १७; १९. २७, ३.
त्रिऽवृता ५. २८, २; ८; १९. २७, ३; ९.
त्रिऽवृति ५. २८, ३.
त्रिवृत्ऽभिः १९. २७, ३; ९^{२}.
त्रिऽवृषः ५. १६, ३.
त्रिऽशताः ११. ७, २.
त्रिऽशीर्षाणम् ५. २३, ९.
त्रिऽशोकः २०. ७६, २.
त्रिऽशोकम् ४. २९, ६.
त्रिषु ७. २७, ३; ९. १४, ९; १०. १०, ११; १२; २०. ६७, ५.
त्रिऽसंधिः ११. ११, २३.
त्रिऽसंधिना ११. १२, ३; २७.
त्रिऽसंधिम् ११. १२, १०; ११.
त्रिऽसंधे ११. १२, २; १८; १९.
त्रिऽसंधेः ११. १२, २; ४; ५; ६; ७; १५.
त्रिऽसधस्थः २०. ८८, १.
त्रिऽसप्ताः १. १, १; २७, १.
त्रिऽसप्तासः १३. १, ३.
त्रिऽस्तुप् ८. ९, २०; १८. २, ६; १९. २१, १.
त्रिस्तुप्ऽछन्दाः ६. ४८, ३.
त्रिऽस्तुभम् ८. ९, १४.

त्रीणि **२.** १, २; **५.** १, १; २८, १^{३}; ७; **७.** २७, ५; **८.** २, २१; ३, १०; ९, ३; **९.** ५, ८; १५, २७; **१०.** ७, ४०; ८, ४^{२}; **१२.** ४, ४७; **१३.** ३, २१; **१८.** १, १७; ३, ४०; **१९.** २७, ३; १०; ३९, २; **२०.** ९१, ५.

त्रीन् **९.** १, ८; १४, १०; **१२.** ३, ४२; **१९.** २७, ४^{६}; **२०.** १३, ४.

त्रेधा **१.** १२, १; **४.** १६, ६; **५.** २८, ६; ७; **७.** २७, १; ४; ४५, १; **८.** ३, १०; **११.** १, ५; १०, ३३; **१३.** ३, २१^{२}; **१८.** ४, ११.

त्रैकंकुदम् **१९.** ४४, ६.

त्रैककुदम् **४.** ९, ९; १०.

त्रैस्तुंभम् **९.** १५, १.

त्रैस्तुंभात् **९.** १५, १.

त्रैस्तुंभेन **९.** १५, २.

त्रैहायनात् **१०.** ५, २२; **१२.** ४, ६१.

त्वचः **६.** २१, १; **१२.** ३, ५३.

त्वचः **५.** १४, ३.

त्वचंम् **१.** २४, २; ३३, ४; **४.** १२, ५; **८.** ३, ४; **९.** ४, १४; ५, ४; **१२.** ३, २१; ११, ७; **१६.** १, १२; **१८.** २, ४; **२०.** १६, ४.

त्वचंम्ऽइव **१९.** २८, ४.

त्वचस्यम् **२.** ३३, ७; **२०.** ९६, २३.

त्वचा **४.** १२, ५; १४, ९; **११.** १०, १५.

त्वचाम् **१२.** ३, ५१.

त्वचि **१.** २३, ४.

त्वचे **११.** २, ५.

त्वत् **३.** ७, ६^{२}; २३, १^{२}; **५.** ११, ४^{२}; **६.** ३०, २; ८७, १; ९०, १; **७.** ८४, ४; ८५, ३; **८.** १, २१^{२}; **९.** १३, १०; ११; १२; १९; २०; **१२.** १, १५; ३, ३९^{२}; **१८.** ३, ५२; **२०.** १५, ४; ८२, २; ११६, १.

त्वत्ऽयोंनयः **१३.** १, २.

त्वद्रिक् **२०.** १७, २.

त्वम् **१.** ७, १; ७; ८, ४; ९, ३; ११, ३^{२}; ६; १७, २; २४, १; ३; ३४, ४; **२.** ३, २; ६, ५; २५, ४; २७, ७; २८, ३; २९, ७; ३६, ८; **३.** ४, १; ५, ६; ७; १२, ५; १८, ५; २०, २; ५^{२}; २३, ४; ५^{२}; ३१, १; **४.** १, ७; ६, ८; ७, ६; ९, ३; १०, ६^{३}; १३, ३; १७, ८; १८, ४; १९, ४; ५; ७; २०, ५; २२, १; ६; ३१, ३; ३२, ३; ४; ३३, ६; **५.** ३, २; ५, २; ४; ६, १०; ८, ७; ११, १; २; ४; ५; ७; १२, १; ३; १३, १०; ११; १४, १; २; २०, २; २१, ४; ५; ६; २२, १०; २८, १०; २९, १; ५; १४; ३०, १७; **६.** ५, ३; १६, २^{२}; ३०, २; ३२, १; ५९, १^{२}; ६३, ३; ६५, १; ७९, २; ८१, २; ८४, ३; ४; ८६, १; २; ३; ९२, २; ९८, २^{३}; ३; १०३, २; ३; १०४, २; १०५, १; २; ३; १०८, १^{३}; ११२, २; ११७, १; १२८, ३; १३०, ४; १३१, ३; १३३, ५; १३४, ३; १३८, १; **७.** २१, २; ३९, ४^{३}; ५८, ४; ६७, १; ७८, ४; ८१, १; ८३, १; ८६, ५; १११, १; ११४, २; **८.** २, १६; ३, १९^{२}; २०; ५, १५; ६, ९; १०; ९, ७; **९.** २, १; ४; ९; १०; १७; १८; १९; २०; २१; २२; २३; २४; २५; ३, ९; **१०.** १, २६; ३, १; १५; १६; ५, ४५; ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६;

१७; २०; २१; ३४; ८, २७^{५}; ९, ३; १२; १०, ८^{२}; १९; **११.** १, १०; ३, २७; **६,** १४; १६; ११, १; ५; ६; १५; १८; २२; २४; १२, ५; १९; **१२.** १, १५^{२}; ६१; २, १; १०; १७; ४५; ४, ४३; १०, ९; ११, ४; **१३.** १, ३२; २, २१; २९; ३, २३; ८, २; **१४.** १, २०; ४३; ५१; ६१; २, ५०; ७१^{३}; **१७.** १, ६; ७; ८; ९^{२}; १०^{२}; ११^{४}; १२^{२}; १३; १४; १५^{३}; १६^{४}; १७; १८^{५}; १९; २०; २१; २४; **१८.** १, १६; २, ३५; ५९; ६०; ३, ६; ८; ४२^{२}; ४, ३१; ५९; ६५; **१९.** १५, १; २८, २; ३०, ३; ३१, ९; ११^{२}; १३; ३२, ५; ३३, ३^{३}; ५; ३५, ३; ४४, १; ४६, ७; ४८, ३; ४९, ८; ५२, २^{२}; ५५, ६; ५७, ४; ५९, १^{२}; ६४, २; ४; **२०.** ५, ३; १२, ४; १५, ६; १८, ६; २१, ८^{२}; ९; १०^{२}; २३, ७; २७, १; २९, १; ३०, ५; ३७, २; ३; ४^{२}; ४६, ३; ४७, १८; ५५, ३; ६२, ६^{२}; ६४, ३; ६७, ६; ६९, ४; ७३, १; ८२, १; ९३, ३^{३}; ५^{२}; ६; ७; ८; ९४, ५; ९५, ३; ९८, २; १०४, ४; १०५, १^{२}; १०८, १; २^{२}; ११४, १; १२६, ४; ८; १३७, १०; ११^{३}.

त्वम्ऽत्व॑म् **२०.** ३०, ५.

त्वया॑ **१.** ७, ५; **३.** ६, ४; **४.** १५, ६; १७, ६; ७; १८, ८; १९, ४; २०, २; ३१, १; ४; ३२, १; ३७, १^{३}; २; **५.** २, ५; ३, १; २९, १; ३०, १६; **७.** ५२, ४; ६७, २; ३; **९.** ५, १६; **११.** २, २०; **१२.** २, ५; १०, १५; **१४.** २, १७; **१८.** ४, ७०; **१९.** ३२, ३; ४; **२०.** १८, ६; २१, ११; ७०, २०; ७९, २; ८७, ४; १०७, ८.

त्वयि॑ **४.** २५, ३; **८.** २, ३; **१२.** १, १५; **१३.** १, ५४; **१८.** २, ५२; ३, ७०; **१९.** ३१, ११^{२}; ४७, ९.

त्व॒र॒णाः **११.** १०, २८.

त्व॒र्य॑ **१२.** ३, ३१.

त्वष्ट॑ः **५.** २५, ११.

त्व॒ष्ट॒ः **२.** २९, २; **५.** २७, १०; **६.** ३, ३.

त्वष्टा॑ **२.** ५, ६; २६, १; **३.** ८, २; २०, १०; ३१, ५; **५.** २५, ५; २६, ८; **६.** ४, १; ५३, ३; ७८, ३^{३}; ८१, ३; ९२, १; १४१, १; **७.** १८, ४; **९.** ४, ६; १०, २; १२, ७; **११.** १०, ८; ९; १८; **१२.** २, २४; **१४.** १, ५३; ६०; **१८.** १, ५; ५३; **१९.** १०, ६; **२०.** ३५, ६.

त्वष्टा॑रम् **४.** ३०, ६; **५.** १२, ९; **११.** ८, ३.

त्वष्टु॑ः **९.** ४, १०; **११.** ४, १४; १०, ९; १८; **२०.** ४१, ३.

त्वष्ट्रा॑ऽइव **१२.** ३, ३३.

त्वा॒ **१.** १०, ३; ४; १२, २; १३, ४; १६, ४; १८, ३; २२, १; २; ३; २३, २; २९, ३^{२}; ३१, ३^{२}; ३४, १; ५; ३५, ४; **२.** २, १; ५, २; ४; ६, १; १०, १^{२}; २; ३; ४; ५^{२}; ६; ७; ८; १२, ३; १३, ५^{२}; २७, २^{२}; ३; २८, ४; **३.** ३, १; ३^{३}; ५; ४, १^{२}; ३; ४^{२}; ५; ६; ७; ५, ८; ७, २; ५; ६; ९, ५; १०, ३; १०; ११, १; ७^{३}; ८^{२}; १२, १; ३; १५, ७; १६, ५; १७, ८; २१, ५; २३, ६; २४, ६; २५, १^{२}; २; ३; ५; २९, ७; ८; **४.** ४, १^{२}; ६, ३; ७, ३; ४; ६; ८, ४; ५; ६^{२}; ९, ५; १०, ७; १३, ५; ७; १५, ४; १६, ९; १७,

१[२]; २०, ६; २२, ५; ३२, ५; ३४, ५[२]; ६[२]; ७[२]; **५.** २, ४[२]; ३, १; ५, २; ६, ११[२]; १२[२]; १३[२]; १४[२]; ७, ७; ८, ९; ११, ७; १३, ४; १४, १[२]; ७; २२, ११; २५, ८; २८, ५; ९[२]; १०; १२[२]; १३[२]; २९, ११; ३०, २; ५; ८; १५; १७; **६.** ९, २; २६, २; २९, ३; ४५, १; ४६, २; ४८, १; २; ३; ८४, १[२]; ८७, १[२]; ८९, ३[२]; ९२, १; ९९, १[२]; १०६, ३; १०९, ३[२]; १११, ४[२]; ११३, १; ३; १३३, ५; १३६, १; १३८, ३[३]; १४२, १; २; **७.** ३६, ३[२]; ३८, १; ३९, ३; ४६, १; ५२, ५; ५८, ७; ७४, १; ७५, २; ७८, ४; ८३, २; ८७, ३; १०२, १; ११५, ३; १२०, १; १२२, १; १२३, १[२]; **८.** १, ३; ७; ९; ११[३]; १२[३]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १९[३]; २०; २, २; ४; ९[३]; १४; १५[२]; २०; २२; २६; ३, ९; १८; २२; ५, १४[२]; १५[३]; २२; ६, ७; ८[२]; २१; ७, २८; ९, १; ७; १५, २; **९.** १, २; ३, ९; ११[२]; २२; २४; ४, १०; ५, २; १५; १५, १३; **१०.** १, ७; ९[२]; ११; १२; १५[२]; १८; २६; २८; २९; ३, ३; ४; ७; १३; १४; १५; ४, ६; ६, ३[२]; ३४; ७, २९; ३०; ८, १०; ३४; ९, २[२]; ७; ८[२]; ९; १०, ७[२]; ९; १०; १६; २२; **११.** १, १; ३; १३; १४; १६; २२; २५; २६; ३२; ३३; ३४; ३, २२; २८; २९; ४, ७; ८; ९; ११; १६; ६, १९; २६; **१२.** १, १८; २९; ३४; ५५; २, ५[२]; ६[२]; १६[२]; ३, २२; २३; २४[३]; ३५[२]; ५५; ५६; ५७; ५८; ५९; ६०; ४, ४३; **१३.** १, १; १०; १२; १५[३]; १७; १८; १९; २०[२]; २१; ३६[२]; ४३[२]; २, ४; ५; १२; २३; ३६; ८, २; ५; ६; ९, १; २; ३; **१४.** १, ४; १९[२]; २०[२]; ४५; ५०; ५२; ५८[२]; २, ७; १९; ३३; ५९; ६०; ६१; ६२; ७०[३]; **१६.** ५, ३; ४; ५; ६; ७; १०; **१७.** १, ८; **१८.** १, ५६; ५७; ६०; २, २१; २२; २५; ३१; ५२; ५४[२]; ५५[३]; ५७; ५८; ३, १; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४९; ६६; ४, ९; ३३; ४४; ४८; ५१; ५२; ६७; ८८; **१९.** १४, १; २५, १; २६, २; ३[२]; २७, १[४]; २[२]; ३; ५; ९; ३४, ६[२]; ७[२]; ३७, २; ३[४]; ४; ३९, २; ३; ४; ९[२]; ४४, ६; १०[२]; ४६, १[२]; २[२]; ३; ४[३]; ५[२]; ६; ७[२]; ४९, ५; ५१, २; ५५, ३; ४; ५६, २; ५७, ४; ६४, २; ६५, १; **२०.** १, १; ३, २; ३; ५, १; ६, १; ८, १; २; ९, ३; १२, ५; १४, २; १५, ४; १८, १; १९, १; २१, ६; २२, १; २; ३; २३, ९; २४, ६; ३०, १; ३२, २; ३८, २; ३; ४२, २; ४७, ८; ९; २०; ४९, ६; ५२, १; २; ५३, २; ५६, ५; ५७, १२; १४; १५; ६२, २; ६३, ६; ६८, ९; ६९, ५; ७२, १[२]; २; ७५, १; ७६, ३; ८१, १; ८५, ३; ८९, ३[२]; ९२, २०; ९३, १; २; ९५, ३; ९६, १; ५[२]; ६; १०; १५; १६; ९९, १; १००, १; २; १०२, ३; १०३, २; ३; १०४, १; १०७, ७[२]; ११७, १; ११८, १; १२०, २; १२१, १; २; १२४, २; १२५, ५.

त्वाऽऊंतासः **२०.** ७०, १८; १९.

त्वाऽदांतम् **२०.** ६, ६.

त्वाम् **२.** ६, ३; १०, २; ३; ४; ५; ६; ७;

८; ३६, ७; **३**. ४, २[२]; ९, ६; **५**. १४, ९; २५, २; **६**. ६३, २; ७८, ३; ८४, ३; **७**. ३९, २; ५; ८५, ४; ८७, ६; **८**. १, ५; २, २३; २७; ५, १४; ७, २६; **९**. ४, ९[२]; **११**. १, ११; २, १३; ३, २७; **१३**. १, ५८; **१७**. १, १४; **१८**. १, १५; १६; ४, ७५; ७६; **१९**. ३०, २; ३[३]; ३१, १३; ३३, ३; ४८, ६; **२०**. १४, १; २; १९, ६; २१, ११; २४, ९; ६२, १; २; ६९, ६[३]; ७१, १०; ८०, २; ८९, ४; ९६, २; ९८, १[३]; १०३, २; १०६, २; ३[२]; १०८, ३; ११५, ३; ११७, २; १२६, ३.

त्वाऽयतः **२०**. २१, ३.

त्वाऽयन्तः **२०**. १८, १.

त्वाऽयवः **२०**. १८, ४; २३, ७; ८४, १.

त्वाऽवतः **२०**. ७६, ४.

त्वाऽवान् **२०**. १२१, २; १२२, २.

त्वाष्ट्रेण **७**. ७८, ३.

त्विषिः **६**. ३८, १; २; **१२**. ६, २.

त्विषितः **४**. ३१, २.

त्विषिम् **१२**. १, ८.

त्विषिऽमती **४**. १९, २.

त्विषिऽमते **६**. २०, २.

त्विषिऽमन्तम् **१२**. १, २१.

त्विषिऽमान् **१२**. १, ५८.

त्विष्या **१०**. ६, २७.

त्वे इति **५**. २, ३; **८**. ९, ९[२]; **२०**. १७, २; १८, ५; ५५, २; ९४, ४; १०७, ६; ११८, २.

त्वेषः **४**. १५, ५; ९. ४, १; **१८**. ४, ५९.

त्वेषऽनृम्णः **५**. २, १; ११, १; **२०**. १०७, ४.

त्वेषम् **१९**. ४७, १.

त्वेषऽसंदृक् **२०**. ३६, ९.

त्वेषसा **२०**. ३५, ११.

त्सरति **८**. ६, ८.

त्सरन् **१२**. ३, १३.

त्सारि **१०**. १, १९.

द

दंष्ट्रारम् **१०**. ४, २६.

दंष्ट्रयोः **४**. ३६, २; **१६**. ७, ३.

दंष्ट्राः **११**. ८, २२.

दंष्ट्राभ्याम् **१०**. ५, ४३.

दंष्ट्रौ **८**. ३, ३.

दंसना **२०**. ७४, २.

दंसनाभिः **२०**. १२५, ५.

दंसांसि **२०**. १३९, ३.

दक्षऽतातिम् **८**. १, ६.

दक्षम् **२**. २९, ३; **४**. १३, २; ५; २५, ५; २८, ५; **७**. १५, ४; **१६**. ४, ७; **२०**. ५९, २.

दक्षमाणः **१**. ३५, ३.

दक्षमाणाः **२**. ४, १.

दक्षाय **६**. १९, २; **१८**. २, २३; **२०**. १४२, ५.

दक्षिणऽअग्निः **९**. ७, १३; **१५**. ६, १४; **१८**. ४, ८; ९.

दक्षिणऽअग्नेः **१५**. ६, १५.

दक्षिणऽअग्नौ **८**. १०, ६.

दक्षिणः **१५**. १८, ३.

दक्षिणतः **४**. ३२, ७; ४०, २; **६**. ९८, ३; **१०**. ९, ८; **११**. ८, १८; **१२**. ३, २४; **१८**. १, ५२; ४, १५; **१९**. १६, १; २७, १४.

दक्षिणम् **४**. १४, ७; **७**. १०, ४; **१२**. १,

३४; १४. १, ४८; १५. १८, २; १८. ४, ५६.
दक्षिणया ६. ५३, १.
दक्षिणऽसव्याभ्याम् १२. १, २८.
दक्षिणा ३. २७, २; ४. ११, ४; ११. ९, ९; १०, २२; १८. ४, ५०; १९. १३, ९; २०. ६५, ३.
दक्षिणा ९. १२, २०; १२. २, ३४; १८. १, ४२; ४, ४६.
दक्षिणाः ९. ११, ६; १५. १६, ७.
दक्षिणाऽज्योतिषम् ९. ५, २२; २४; २५; २६; २८; ३१; ३२; ३३; ३४; ३५; ३६.
दक्षिणात् ७. २७, ८.
दक्षिणानाम् १८. ४, ८.
दक्षिणाभिः १९. १९, ६.
दक्षिणाम् ५. ७, १; ११, १; ९. ५, १४; १०. ५, ३७; १२. ३, ८; १३. १, ५२; १५. २, ९; १४, ३; १८. ४, २९.
दक्षिणायाः ४. ४०, २; ५. १०, २; ६. ५८, १; ९. ३, २६; १४, ९; १५. ४, ४; ६; ५, ४; ५; १८. ३, २६; १९. १७, ३; १८, ३.
दक्षिणायाम् ३. २६, २; ४. १४, ७; १५. २, १२; १८. ३, ३१.
दक्षिणायै १२. ३, ५६.
दक्षिणाऽवति २०. ५५, ३.
दक्षिणाऽवते १८. ३, ४९.
दक्षिणाऽवन्तः १८. ३, २०.
दक्षिणीयः ८. १०, ७.
दक्षिणे ४. २०, ४; ७. ५२, ८; २०. ३६, ९.
दग्धऽअन्नस्य १९. ५५, ५.
दग्धाः १८. २, ३४.
दग्धायाम् ४. १८, ३.
दण्डः ९. १, २१.
दण्डनम् १२. २, ५४.
दण्डम् १८. २, ५९.
दण्डेन ५. ५, ४; १०. ४, ९; ८, २७.
दतः ५. २९, ४; ६. ५६, ३; १९. ६१, १.
दता ६. ५६, ३.
दताम् ५. २३, ३.
दत्त ६. २४, ३; ७. ५२, ९.
दत्त ११. ८, २३; १४. २, २९; १९. २, ५.
दत्तः २. २९, ४; ३. ५, ४; २९, १; २; ९. ४, ७; ५, ७; ११; १२. ३, ४२; १४. २, ४२.
दत्तम् ४. ९, १; ६. ७१, २; ८९, १; १२२, १; २; १४. २, ४१; ४२; १८. २, ५७; १९. ३७, १.
दत्तम् ६. ११८, २; १९. ४२, ४.
दत्तस्य २०. ४३, ३.
दत्ता ५. ७, ५; १०. ९, १; १८. ४, ५०.
दत्तात् ६. १२३, ४.
दत्तात् १८. २, ५.
दत्ताम् ७. १०९, १.
दत्ताम् ३. १, ६; ६. ११८, १.
दत्ते ९. ५, ३२; ३३; ३४; ३५; ३६.
दत्तेन २. ४, ४.
दत्तो इति १८. ३, १४.
दत्त्वा ९. ४, १९; ५, २९; १०. १०, ३३; ११. १०, १०; १४. २, २८; ७४; १९. ७१, १.
दत्ऽभिः २०. १६, ६.
दत्ऽभ्यः ११. २, ६.
दत्राणि २०. ५१, २.
दत्वताम् ४. ३, ४.
दत्वती ४. ३, २; ७. ११३, १; १९. ४७, ७.

दत्से १२. १०, १०.
दत्स्व ५. २१, १०.
ददत् ३. १६, ३; १२. ४, २३.
ददत् १४. २, ४[२]; १८. २, ५४.
ददतः ६. १२२, २; १०. १, ११; २०. ३७, १०.
ददति ८. १२, ४; १२. १, २२.
ददती १२. १, ३७.
ददतु ३. ५, ३; १०. ६, २९.
ददते १०. ८, ३६.
ददन् ६. २४, १.
ददन्ते १०. ८, ३५.
ददम्भ ५. २९, ६; ७; ८; ९.
ददर्शं ९. १५, १०.
ददर्श ९. १४, ४; १८. १, ७.
ददाः १२. ४, ५२.
ददात् ११. १, २७.
ददातः ९. ५, २७.
ददाति ३. २९, ३; ४. २१, ३; ९. ५, २२; २४; २५; २६; २८; ३१; ३२; ३३; ३४; ३५; ३६; १०. ९, ५; ६; १०; १४. २, ४१.
ददाति ४. २१, २; ६. ६३, २; ८४, ३; ९. ४, ९; ५, ११; १२; १८. १, ५५; ४, ३१; १९. ५, १; २०. ६७, १[२]; ९६, ३.
ददातु ७. ४९, १; ५०, १.
ददातु ६. ३३, ३; १२२, ५; ७. ८५, २; ८. ३, १६; १२. १, ४४; ३, ५५; ५६; ५७; ५८; ५९; ६०; १९. ३७, १; ४८, २.
ददातै १२. ३, २४.
ददामि ५. ११, १०; १२. ४, १; १८. ३, ३७.
ददामि १. ३०, २; ३. ११, ७; ४. ३४, ७; ५. ११, ८; ६. १२२, १; १२३, १; ४; ७. ५५, ४; १२. ३, ४७.
ददावान् ५. ११, १.
ददासि ७. ५०, २.
ददिः ५. १३, १; २०. ५६, ४; ६७, ७; ९५, ४.
ददिऽवांसम् ९. ५, १०.
ददीमहि २०. ७०, १९.
ददुः १०. १०, ३२.
ददुः ५. १७, १०; १०. २, २९; १२. १, ५३; १९. ३५, १.
ददृशे १९. ४७, २.
ददृशे १०. ८, ८.
ददृशे ९. १५, २६; १०. ८, ४१.
ददृश्राम् १२. ३, ३३.
ददे २०. १४३, ५.
ददे १. ९, ४; २. १२, ४; ४. ३६, ४; ६. १३५, १; ७. १३, ३; १४, १; २; ११९, १[३]; १०. २, १६; ४, २४; १९. १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ४९, ४.
ददौ १९. ३४, ८.
दद्मः ६. ९९, २; ३; ११७, २; १२. ३, ४६; ५५; ५६; ५७; ५८; ५९; ६०.
दद्मसि १. १४, ३; ५. २२, १४; ८. २, २०; २२; १९. ४८, १.
दद्यात् ३. २८, २; ९. ५, १४.
दद्राणम् ९. १५, ९.
दद्रुषीणाम् ५. १३, ८.
दधः २०. ५६, ३[२].
दधत् ६. ११, ३; ७. १५, ४; ९. ४, २२; १०. ६, ४.
दधत् ४. १२, २; ७; १९, ८; २०, ४; ५.

२५, १; ६. ११, ३; ७. ५५, ६; १०. ३, १२; ११. ६, ११.
दधतः १८. ४, ६२.
दधताम् ८. ८, २; १२. २, २३.
दधते ११. ६, ३.
दधथः २०. १४३, ४.
दधथुः १८. २, ५३.
दधन्विरे २०. ३१, १; २.
दधर्षति ४. २१, ३; ६. २८, २.
दधात २०. ५९, ४.
दधात ६. ५५, २; १४. १, ५९; १८. १, ५१; ३, १४; ४३; ४४.
दधातन १. ५, १; २०. १३७, २.
दधाति ५. १, ७.
दधाति ३. ३१, ६; ४. ८, १; २१, २; ५. २, २; १७, ६; ६. ७६, ३; ९. ५, १०; १८; ११. ७, १३; २०. ५९, ३; ९६, ४; १०७, ५.
दधातु ६. ६०, ३.
दधातु १. १, १; ३. ८, १; १५, ६; २०, ३; १०; ५. २५, ४; ५; २८, ५; ६. ४५, २; ४७, १; ९२, १; ७. ५, २; १०, ४; १८, १; २; ३; ४; २०, १²; ४९, २; ८. १, १५; ४, ९; ५, १८; २१; ९. ४, २१; १२. १, ३; ४; ५; ६; ८; २२; ४४; ५२; १३. १, १७; १८; ३५; १६. ४, ७; १८. २, ५५; ३, ६२; १९. ३१, ३; ६; ९; ४०, १; ४३, १; २; ३; ४; ५; ६; ८.
दधानः १३. १, २; १८. १, २४; २०. ११, ५.
दधानम् २०. ५५, १.
दधानाः ४. २, ६; ३१, ७; १२. २, ३०; १८. ३, १७; २०; २०. २१, ११; ३३, ३; ४०, ३; ६८, ५; ६९, १२; ९१, २.
दधानान् २०. ३४, १०.
दधाने इति ५. १२, ६.
दधानौ ७. ३०, १.
दधामि ७. ३८, १.
दधामि २. १०, ५; १२, ८; ४. ३०, ६; ३६, २; ५. २५, २; ७. ८७, २; ८. २, २; ९; ८, ८; ९; ११. १, २०; १२. २, २३; ३, २३; १३. १, १९; १६. ७, ३; १८. ३, ३०; ३१; ३२; ३३; ३४; ३५.
दधार ६. ६०, ३.
दधासि ७. ८६, २; १४. १, २४.
दधिऽआशिरः २०. ६९, ३.
दधिक्रावाऽइव ३. १६, ६.
दधिऽक्राव्णः २०. १३७, ३.
दधिम २०. ८९, ६.
दधिरे १. ३३, १; २; ३; ८. ४, १८.
दधिरे ६. ४९, ३; २०. २५, ४; ८८, १.
दधिऽवान् १८. ४, १७.
दधिषे १९. ४९, ७; २०. ५५, ३; ८७, २.
दधिषे ५. २, ६; २०. १५, ६; ३१, ५; १०७, ९.
दधिषोः १८. ३, २.
दधिष्व २०. ६, ५.
दधिष्व २०. २०, ३; २४, ५; ५७, ६; ८४, ३.
दधीचः २०. ४१, १.
दधीत १८. १, १.
दधुः १९. ५६, ३.
दधृक् १८. २, ५८.
दधृषते ६. ३३, २.
दधृषन्त ३. ३, २.
दधृषम् २०. २४, ६.
दधृषुः १. २७, ३.

दधे २०. ११९, २.
दधे ४. ७, ७; २७, २; ३४, ८; ५. ६, २; ९, ७; ३०, १२; ७. २७, ४; ८. ५, ६; ११. १, २८; ३३; १७. १, २९; १९. ४, २; २०. ५३, १; २; ५७, ११; १२.
दधेते इति ५. १, ३.
दधौ ९. ४, १०; १०. २, ५; १७; १९. ३४, ९.
दध्नः ३. १२, ७; ७. ७६, १.
दध्ना ४. ३४, ६; ७.
दध्मः ३. २७, १; २; ३; ४; ५; ६; ४. ५, ५; ९. ४, २४; १२. १, ३०; १९. ७२, १.
दध्मसि १९. ६४, ३.
दध्मसि १. २२, १; २; ३; ४[2]; ३. २३, १; ५. २१, १; ८. १, २१; १४. २, ६५; ६९.
दध्रे १८. ३, ६३; १९. २६, १.
दध्रे १२. १, ३७; २०. ५, ७.
दन्ताः ४. ३, ६; ५. १८, ८; ९. १२, ३; ११. ४, ६; १९. ६०, १.
दन्तैः ११. ४, ६[2].
दन्तौ ६. १४०, १; ३.
दन्तौ ६. १४०, २; ३.
दभन् ४. ७, ७; ५. २, ४; ६, २; ८. ३, ९; ६, २५; १३. २, ५; १७. १, ८; १९. २७, ५; ६; ४६, २; २०. २२, २; १०७, ७.
दभन्ति २०. ५९, ३.
दभाति ४. २१, ३; ६. २७, ३.
दभायत् ४. १, ७.
दभीतये २०. ३७, ४.
दभ्नुहि १०. ३, ३.
दभ्रम् ८. ४, १०.
दभ्रस्य २०. ५६, २.
दमयन् ५. २०, १.
दमिता २०. ११, १०.
दमूनाः ७. १५, ४; ७७, ९; १९. ४९, १.
दमे २०. ३५, ९.
दमेऽदमे ७. ३०, १; २.
दंपतिऽभ्याम् १२. ३, २७.
दंपती इति दम्ऽपती १२. ३, १४; ३५; १४. २, ९; ११; ६४; १८. १, ५; २०. १६, २; ९६, १४.
दंपती इति दम्ऽपती ६. १२२, ३; १२. ३, ७.
दम्ऽपते २०. ९२, १३.
दम्भय ७. ९५, १.
दयताम् ८. १, ५.
दयमानः २०. ११, १.
दयसे २०. १२, ४; ५.
दयसे २०. ३६, ९.
दयस्व ८. २, ८.
दयामसि १९. ५७, ५.
दये १६. ७, ११.
दरयन्तः २०. २१, ४.
दर्ता २०. ६४, ३.
दर्दः २०. ७७, ८.
दर्दरीति २०. ९०, २.
दर्दर्षि २०. ३४, १८.
दर्भ १९. ३३, २.
दर्भ १९. २८, २; ३; ४; ५; ६; ७; ८; ९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९; ३०, १; २; ३; ४; ३२, ८.
दर्भः ६. ४३, १; २; ८. ७, २०; १०. ४, २; ११. ८, १५; १९. ३०, ५; ३२, १; ९; १०; ३३, १,

दर्भम् १९. २८, १; ३३, ५.
दर्भेण १९. ३२, २; ७; ३३, ५.
दर्भेषु १०. ४, १३.
दर्माणम् २०. ३९, ५.
दर्विः ९. ६, १७; ११. १, २४; ३, १६; १२. ३, ३६.
दर्विम् १०. ४, १३.
दर्वे ३. १०, ७.
दर्व्यौ ४. १४, ७.
दर्श ७. ८६, ३.
दर्शः ७. ८६, ४.
दर्शतः ४. १०, ६; ७. ८६, ४; २०. ९२, १७; १०२, १; १०५, ५.
दर्शतम् १८. १, १७.
दर्शति ५. २, ७; २०. १०७, १०.
दर्शन् ५. १, ८.
दर्शय ४. २०, ६[२].
दर्शय ४. २०, ६; ९; ११. ११, १; १५; २२; २४.
दर्षि २०. ९२, ३; ९७, १६; ७७, ८.
दविद्युतत् ७. ६४, १; २०. १७, ४.
दविध्वतः २०. ३१, ४.
दवीयः ६. १२६, १; १०. ८, ८.
दश ५. १५, १; १०; १७, ८; २८, ११; ९. १४, १४; ११. २, ९; ९, ४; १०, ३; १०; १३. ४, ६; २०. ३१, ६; ९.
दश ५. १४, १०.
दशऽअङ्गुलम् १९. ६, १.
दशऽआस्यः ४. ६, १.
दशऽऋचेभ्यः १९. २३, ७.
दशऽओणिम् २०. ३२, २.
दशऽग्वम् २०. ६३, ८.
दशऽपक्षाम् ९. ३, २१.
दशऽभिः ७. ४, १; ८. ४, १९; ११. २, २३; २०. १३७, ७.
दशमः १३. ५, ९.
दशमम् २०. ६६, २.
दशऽमास्य १. ११, ६.
दशऽमास्यः ३. २३, २.
दशमीम् ३. ४, ७.
दशमे ५. २९, १०; ११; १२; १३.
दशऽवृक्ष २. ९, १.
दशऽवृषः ५. १६, १०.
दशऽशताः ५. १८, १०.
दशऽशलात् ८. ७, २८.
दशऽशाखाभ्याम् ४. १३, ७.
दशऽशीर्षः ४. ६, १.
दशस्य २०. ४६, ३.
दशस्यन् २०. ३९, ११.
दशस्येत् १८. १, १०.
दशोनसिम् १०. ४, १७.
दष्टम् ७. ५८, ३.
दसत् ५. ३०, १५.
दस्म २०. १७, २; ६८, ६; ७३, २.
दस्मम् १८. १, २१; २०. ९, १; ४९, ४.
दस्म्यम् २०. ६५, २.
दस्यति ३. २९, २; ६[२]; १२. ४, २.
दस्यवः १८. २, २८.
दस्युऽभ्यः २. १४, ५.
दस्युम् २०. २१, ४; ३७, ४.
दस्युऽहा ४. ३२, ३; २०. ४२, २; ७८, ३.
दस्यून् ४. ३२, ६; ९. २, १७; १८; ११. १, २; १२. १, ३७; १९. ४६, २; २०. ११, ६; ९; २९, ४.
दस्यूनाम् ३. १०, १२; ८. ८, ५; ७; १०. ६, २०.

दस्यून्ऽइव १०. ३, ११.
दस्योः १. ७, १; २०. ३४, १०; ६४, ३.
दस्रा ७. ७७, २; २०. १४३, ६.
दह १२. ११, १; १९. २९, ८^{४}.
दह १. २८, २^{२}; ३. २, ५; ५. २९, ११; ६. ३२, १; ७. ११३, २; ८. ३, १८; ९. २, ४; १२. ११, १^{२}; १८. ३, ७१.
दहः १८. २, ४.
दहतः ६. २०, १; ७. ४७, १^{२}.
दहतम् ३. १, ३.
दहति ४. ३४, २; ९. ५, ३१; ३२; ३३; ३४; ३५; ३६.
दहतु ४. ३६, १; १२. १०, १५; १३. १, २९.
दहन् १. २८, १; ६. ३७, २.
दहन्तु ८. ३, १९.
दहामसि १३. १, २९.
दहामि ५. २३, १३.
दह्यन्ते १२. ४, ३.
दाः २. ६, ५; १७, १; २; ३; ४; ५; ६; ७; १८, १; २; ३; ४; ५; ३. १२, ५; ५. ३, ८; १४. १, ३७; २, १.
दाक्षायणम् १. ३५, २.
दाक्षायणाः १. ३५, १.
दात् १८. १, ४१; ४, ४५.
दातवे ३. २०, ५.
दाता ३. २९, ७; ४. ११, ५; ११. ३, २५; १९. ५५, ३; ४; २०. १०४, ४.
दाताम् १८. २, १३.
दातारम् ३. २१, ४; ९. ५, ९.
दातुः ६. ५८, १; १८. ४, ४९.
दातुम् ६. १२२, २; १२. ४, १८.
दातॄणाम् ५. २४, ३.
दात्रे ९. ३, १२; ४, १; १०. ९, १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १०, २७.
दाधार ४. ३५, ३; ६. १७, २; ३; ४; २०. ६१, ५; ६२, ९.
दाधार ४. २, ७; ११, १^{३}; ५. १, १; १०. ७, ३५^{३}; ८, ११; ११. ७, १; १८. ४, ५^{२}.
दानऽऔकसम् २०. ३५, ५.
दानऽकामः ३. २०, ६.
दानम् २०. ११८, २.
दानम् २०. ७८, २.
दानवानाम् ४. २४, २; १०. ६, १०.
दाना २०. ५३, २; ५७, १२.
दानाय ३. २०, ५; ७.
दानाय २०. ५८, २.
दानुना २०. १७, ७.
दानुम् २०. ३४, ११.
दानेन १२. ४, ३२.
दान्ति २०. १२५, २.
दान्तु १२. ३, ३१.
दापयतु ३. २०, ८.
दाम ६. ६३, १.
दामने २०. ४७, २; १३७, १३.
दामानम् २०. ८९, ८.
दाम्ना ६. १०३, २; ३.
दायादः ५. १८, ६; १४.
दायि २०. ३५, १५.
दारु १०. ४, ३; ४.
दारुणि ६. १२१, २.
दारूणि १९. ६४, ३.
दावने २०. ३५, १०; ९२, १४; ९४, ७.
दावस्य ७. ४७, १.

दाशसि १८. १, ३८.
दाशुषः ४. २४, १.
दाशुषे ७. १८, २; ३; २१, १; ४१, २; ५०, २; ११५, १; १८. १, ४१; ३, ४३; ४, ४५; १९. ५, १; २०. ३५, ११; ३७, ६; ५१, २; ६०, ४; ५; ६३, ४; ६६, १; ७१, ४; ५; ९२, १०.
दाश्वंसम् ७. ४१, २.
दासः ५. ११, ३.
दासम् ४. ३२, १; २०. ११, १; ३४, ४; ३७, २; १२६, १९.
दासय १२. १०, ६.
दासयति १२. ७, १६.
दासस्य ७. ९५, १.
दासाः ४. ९, ८; ५. ११, ६.
दासानि २०. ३६, १०.
दासाय ५. २, २; २०. १०७, ५.
दासी ५. १३, ८; १२. ३, १३; ४, ९.
दासीम् ५. २२, ६.
दास्यन् ६. ७१, ३.
दास्वन्तम् २०. ६७, ३.
दिक् ३. २७, १; २; ३; ४; ५; ६.
दिक्ऽभ्यः ४. ४०, ८; १०. ५, २८; १३. ७, ६.
दिक्षु ३. २१, ७; ४. १४, ९; ३९, ७²; ५. ११, ८; ९; १८. १, ४६; १९. ८, १; ४९, ५.
दिक्ऽसंशितः १०. ५, २८.
दिग्धा ५. १८, १५.
दितिः ११. ३, ४; १५. ६, २०; १८, ४.
दितेः ७. ८, १; १५. ६, २१.
दित्सति १२. ४, २; १२; १३; १९.
दित्सन्तः ५. ७, ६.
दित्ससि २०. २७, ४.
दित्सेयम् २०. २७, २.
दिदिड्ढि ७. ४८, १.
दिदेव ५. २९, २.
दिदेश १२. २, ५५.
दिदेश १४. २, १३.
दिद्युत् २. २, ४.
दिद्युम् १. २, ३; २०. ८३, १.
दिधिषेय २०. ८२, १.
दिधृत २०. ६७, २.
दिप्स ५. १४, १.
दिप्सत् ४. ३६, २.
दिप्सतः ४. ३६, २; ३.
दिप्सति ४. ३६, २; ५. १४, २; ७. ११३, १; ८. ४, १०; ११; ६, ८.
दिप्सन्तम् ५. १४, १.
दिप्सन्ति १०. ३, १६; १९. ४९, ७; ६५, १.
दिप्सन्ति ८. ४, २०.
दिप्सवः ८. ४, २०.
दिप्सात् ४. ३६, १.
दिवः ४. २०, २; ३४, ४; ११. ९, १४; १३. ३, २१; १९. २७, ३; २०. १४३, २.
दिवः १. ११, २; २. ५, २; ७, ३; ४. १, ४; १४, २; ३; १५, १०; १६, ४; २७, ४; ५. ६, ३; १३, १; २४, ११; २५, १; २८, ९; ६. ३७, २; ५२, १; ८६, १; १००, ३; १२४, १; १२५, २; ७. १०, १; २२, १; २७, ८; ५७, २; ७७, १; ४; ११२, १; ८. ४, ४; ५; १९; ६, १२; ७, २०; ९. १, १; २, २१; ४, २१; १४, १०; १२; १०. ५, २७; ७, ३; ९, ५; १०, ३२; ११. २, ४; २७; ७, १०; १२. १, २०; २, १२; ३, २६;

११, १२; **१३.** २, ३६; ३७; ४१; ४, १; ७, ५; **१६.** ७, ६; **१७.** १, १०; **१८.** १, २; १८; ६१; २, ३५; ३, ६५; ४, ५८; **१९.** ३, १; १६, २; २७, १५; ३२, ४; ३५, ४; ४४, ५; ४७, १; **२०.** १, २; २८, ३; ३५, ९; ३९, ४; ६२, ७; ६४, १; २; ३; ७०, ५; ६; ७७, ३; ९१, २; १४३, ५; ९.

दिवः **१९.** ४७, ५; **२०.** ६७, ४.

दिवःऽदिवः **७.** १५, ३.

दिवम् **२.** ३४, ५; **३.** २१, ७; **४.** १४, ३; २०, १; ९; २७, ४; **४.** ३४, ५; ३५, ३; **५.** १९, १; **६.** २२, १; **७.** १०२, ४; **८.** ५, ७; **९.** ५, २९; १५, २२; **१०.** २, ८; १८; ५, २७; ७, ३२; ४४; ८, ३६; ९, ३; १०; ११; २५; **११.** ७, १; ८; ९; ८, १०; **१२.** २, १७; ३, २५; **१३.** १, ८; ९; १६; २४; २५; २६; ३४; ४५; ५२; २, ४; ५; ८; २५; ४०; ४१; ३, ९; १३; १६; **१४.** २, ६९; **१५.** ४, १७; १०, ११; **१७.** १, ८; **१८.** २, ७; ९; ३, ६४; ४, १४; **१९.** २२, २१; २३, ३०; ३२, ९; ५३, ५; ६५, १[३].

दिवा **५.** ७, ३; २९, ९; ३०, १०; **६.** २३, १; १२८, ४; **७.** १०६, १; **८.** ३, १; ४, ११; ५, २२; **११.** २, १६; **१६.** ७, १०; **१९.** १५, ६; ३९, २; ३; ४.

दिवा **४.** ३०, ८; **११.** ४, ९; **१२.** १, ६३; **१८.** १, १०; **१९.** १९, ३; ३२, ९.

दिवाऽकरः **४.** १०, ५; **१३.** २, ३४; **२०.** १०७, १३.

दिवि **१.** ३०, ३; ३२, १; ३३, ३; **२.** २, १; २; **३.** ७, ४; १७, ७; **४.** १०, ४; ३९, ५[२]; **५.** ४, ३; ४; **६.** ६९, ३; ७५, ३; ८०, २; ३; ९५, १; २; **७.** १०२, ८[२]; **९.** १, २०; ११, ९[२]; १५, ३; **११.** ८, १३; ९, २३; २४; २५; २६; २७; १२, २; ८; १०; **१२.** ३, ५०; **१३.** १, ३९; ४४; २, १; १२; ३०; ३, १६; २३; **१४.** १, १; ११; **१५.** १३, ६; **१७.** १, १२[२]; **१८.** २, ५०; ४, ५९; ८९; **१९.** ६, ३; ७, १; ८, १; २७, ११; ३२, ३; ७; ३९, ६; ७; **२०.** २५, ६; २६, ४; २७, ५; ३०, ४; ३८, ६; ४७, ६; १०; ६९, ९; ७०, ९; १३९, २.

दिविऽइव **६.** ९२, ३; **७.** २७, ७.

दिविऽचराः **१९.** ९, ७.

दिविऽश्रितः **११.** ९, २३; २४; २५; २६; २७.

दिविसत्ऽभ्यः **१८.** ४, ८०.

दिविऽसदः **१०.** ९, १२; **११.** ८, १२.

दिवे **१.** ३२, ४; **५.** ९, १; ५; **६.** १०, ३; २०, २; **१९.** ११, ६; **२०.** ९२, १७; १०५, ५.

दिवेऽदिवे **७.** ७४, १; **८.** ३, २२; **२०.** ६१, ३; ८२, २; ८७, २; १००, २; १३७, ६.

दिव्य **२.** २, १.

दिव्यः **२.** २, १; **७.** ४२, २; **८.** १, ११; **९.** १५, २८; **१०.** ५, २०; **१३.** २, ९; **२०.** १२१, २.

दिव्यम् **४.** १४, ६; **७.** १९, १; ४०, १; **१८.** १, ३२; **२०.** ३०, २.

दिव्यस्य **४.** २०, ३; **६.** ८०, १; ३; **७.** १९, १; **२०.** १७, १२; ३६, ९; ८७, ७.

दिव्या **६.** १४२, १; **१९.** ४९, ८.

दि॒व्याः **४.** ८, ४; ५; ६; **७.** ९४, १; **८.** २, १४; ७, ३; २४; **९.** ५, १४; **१०.** ५, ४६; ९, ६; **११.** २, २४; ७, २१; ८, ८; **१६.** १, १; **१९.** ११, २; ४.
दि॒व्यात् **८.** ४, २३.
दि॒व्या॒नाम् **१९.** २, ४.
दि॒व्यानि॑ **२०.** ३६, ८.
दि॒व्याम् **११.** २, १९.
दि॒व्ये **७.** ८७, ६.
दि॒व्ये इति॑ **५.** १२, ६.
दि॒व्येन॑ **२.** ६, १; **११.** २, २६; **२०.** १७, ७.
दि॒व्येषु॑ **७.** ७०, १.
दिशः॑ **४.** ८, ४; ३९, ८; **५.** २१, ९; २८, २; **६.** ८८, ३; **८.** ५, १३; ८, ५; २२; ९, १५; **९.** २, २१; ५, २०; ३७; **१०.** २, २८; ५, २८; ३८; ६, ९; ७, ३४; ८, ३५; ९, १०; **११.** ८, ६; **१३.** १, ३८; २, २; ४१; ३, ६; १९; ७, ६; **१५.** ६, २२; **१८.** ४, ६; ७; **१९.** ६, ८; २०, २; ४५, ३; ४; ५४, १.
दि॒शः **४.** ४०, १; २; ३; ४; ५; ६; ७; **५.** १०, १; २; ३; ४; ५; ६; **६.** ९८, ३^{२}; **९.** ३, २५; २६; २७; २८; २९; ३०; **१५.** ४, १; ३; ४; ६; ७; ९; १०; १२; १३; १५; १६; १८; ५, १; २; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; **१८.** ३, २५; २६; २७; २८; **१९.** १७, २; ३; ४; ५; ६; ७; ८; ९; १०; १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
दि॒शःऽदि॑शः **४.** १५, ८; **९.** ३, ३१; **१०.** ३, १०; **१८.** ४, ९; **१९.** ३५, ४.
दि॒शा॒तु **१२.** १, ४०.
दि॒शन्ता॑ **५.** १२, ७.
दिशं॑म् **१२.** ३, ८; **१५.** २, १; ९; १५; २१; ६, १; ४; ७; १०; १३; १६; १९; १४, १; ३; ५; ७; ९; १७.
दिशं॑म्ऽदिशम् **३.** ३१, ४.
दि॒शाम् **४.** ४०, ८; **५.** १०, ७; **१२.** ३, ९; १०; **१३.** २, २.
दि॒शि **३.** २६, १; २; ३; ४; ५; ६; **४.** १४, ७^{२}; ८^{४}; **११.** २, १२; १४; २७; **१५.** २, ४; १२; १८; २४; **१८.** ३, ३०; ३१; ३२; ३३; ३४; ३५.
दि॒शे **१२.** ३, ५५; ५६; ५७; ५८; ५९; ६०.
दि॒ष्टः **५.** ३०, १७.
दि॒ष्टम् **१२.** ३, ५५; ५६; ५७; ५८; ५९; ६०.
दि॒ष्टात् **१०.** ३, १६.
दि॒हा॒नः **८.** ३, ६.
दी॒क्षया॑ **१२.** ५, ३; **१९.** ४३, १; २; ३; ४; ५; ६; ७; ८.
दी॒क्षा **११.** ९, ८; **१२.** १, १; **१५.** १६, ५.
दी॒क्षाः **८.** ९, १७.
दी॒क्षाभिः॑ **८.** ५, १५.
दी॒क्षाम् **९.** ६, ४; **१४.** २, ५२; **१९.** ४०, ३; ४१, १.
दी॒क्षि॒तः **१०.** १०, १२; १७; **११.** ७, ६.
दी॒दय॑त् **१४.** १, ३७.
दी॒द॒य॒त् **३.** ८, ३.
दी॒दय॑ति **१८.** ४, ८८.
दी॒द॒य॒न्ते॒ **१८.** ३, ७३.
दी॒दि॒हि **७.** ८३, २.
दी॒दि॒हि॒ **२.** ६, १; ४; **७.** ७८, ४; ८९, १; **१२.** २, १८.
दीद्यं॑तम् **२०.** १०२, ३.
दी॒द्य॒ति॒ **१०.** १०, २८.

दीधाथाम् २. १२, ९.
दीधिम २०. ९८, १.
दीधीथाः ८. १, ८.
दीध्यः ८. १, ९.
दीध्यतः १८. ३, २१.
दीध्यानः १८. १, १.
दीध्यानाः २. ३४, ३; १८. २, ४७; २०. ८८, १; ९१, २.
दीध्युः १४. १, ४६.
दीने २०. १६, ८.
दीपयः २०. ३६, ८.
दीपयामसि १२. २, ९.
दीप्यते १०. ७, २; ४.
दीय १९. १३, ८.
दीयते १२. ४, ३.
दीयमानः ९. ५, ९; १०.
दीर्घऽआयुः १४. २, २; ६३.
दीर्घः २०. ५, ४.
दीर्घऽतमाः २०. १४०, ५.
दीर्घम् १. ३५, २; २. १३, २; ३. ८, ३; ६. ७८, ३; ७. ३३, १; ३४, १; ८६, २; १०८, १; ८. २, ११; ११. १, ३४; १२. १, ६२; १३. २, ३७; १४. १, २४; ४७; २, ३९; ७५; १८. २, ३; १९. २४, ४.
दीर्घऽश्मश्रुः ११. ७, ६.
दीर्घऽश्रवसः २०. ७३, ४.
दीर्घाम् १४. १, ४६.
दीर्घायं ६. ३९, १; २०. ३८, ६; ४७, ६; ७०, ९.
दीर्घायुऽत्वाय १. २२, २; ३५, १; २. ४, १; ३. ५, ४; ४. १०, ७; ५. २८, १; ६. ६८, २; ११०, २; १३३, ५; ८. ५, २१; १२. २, ६; १४. २, ७५; १८. ४, ५३; १९. २८, १.
दीर्घेण १२. २, ३२; ५५.
दुः ६. १११, ४[२].
दुःऽअर्मण्यः १६. २, १.
दुःऽआधर्षा १२. ७, ६.
दुःऽआध्यः २०. ७९, २.
दुःऽइतम् ६. १२१, १; ७. ८८, ४; ८. २, ७; ७, ९; ९. २, ३; १०. १, २५; ३२; ५, २४; १४. २, ६६; ६७.
दुःऽइतस्य ३. ११, ३; २०. ९६, ८.
दुःऽइता २. ६, ५; ६. २८, १; १२६, २; १२. २, २८; २०. ३१, ३.
दुःऽइतात् २. १०, ६; ५. ६, ८; ६. ४५, ३; ७. ६६, १; ८. ७, ७; १९; १०. ५, २२; १२. २, ४७; ४८.
दुःऽइतानि ५. २८, ८; ६. ५३, २; ११०, २; ११२, ३; ११३, २; ७. ६५, १; १३. १, ५८; २, ३४; १९. ३३, ३; २०. १०७, १३.
दुःऽइते २. १२, २.
दुःऽइष्टिः २. ३५, १.
दुःऽएवाः ८. ३, १६; २४; १२. २, २६.
दुःऽएवाम् ७. ५२, ७; २०. १७, १०; ८९, १०; ९४, १०.
दुःऽएवासः ५. २, ४; २०. १०७, ७.
दुःऽकृतः ८. ४, ३; १९. ५६, ५.
दुःऽकृतम् ४. २५, ४; ७. ६७, २; ११. १०, २०; १२. २, ४०; १४. २, ६६.
दुःऽकृतात् ४. ९, ६.
दुःऽकृतानि ६. ४५, २.
दुःऽकृते ८. ४, ७; १०. १, २३; २०. १२६, ५.

दुःऽगन्धीन् ८. ६, १२.
दुःऽगम् १४. २, ११.
दुःऽगहानि २०. ३६, ७.
दुःऽगा १२. ४, २३.
दुःऽगाः १०. १, १६.
दुःऽगान् १३. २, ५.
दुःऽगानि ७. ६५, १; ९. ५, ९; १९. ५०, २.
दुःऽचरितम् ९. ५, ३.
दुःऽचितः ५. ३१, ५.
दुःऽचितम् ११. १२, २६; १२. १०, १५.
दुःऽच्यवनः १९. १३, ७; ३२, १.
दुःऽच्यवनेन १९. १३, ३.
दुःऽदाशे १. १३, १.
दुःऽधरम् २०. १५, १.
दुःऽधाम् ५. १७, ६.
दुःऽध्यः २०. ९४, ७.
दुःऽनशम् ५. ११, ६.
दुःऽनामा ८. ६, १; ४; २०. ९६, ११; १२.
दुःऽनामानः ११. १२, २.
दुःऽनाम्नः १६. ६, ७; १९. ३६, ४; ५.
दुःऽनाम्नाम् २. २५, २.
दुःऽनाम्नीः ४. १७, ५; ७. २४, १.
दुःऽनाम्नीनाम् १९. ३६, ६.
दुःऽपदा २०. २१, ९.
दुःऽप्रतिग्रहा १०. १०, २८.
दुःऽभगाम् १०. १, १०.
दुःऽभूतम् ३. ७, ७; ८. २, १२; १०. १, १३; ३२.
दुःऽमतिम् १४. २, ६.
दुःऽमत्यै ६. १३, २.
दुःऽमन्तु १८. १, ३४.
दुःऽयुजः २०. ९४, ७.
दुःऽवाचः ४. १७, ५; ७. २४, १.
दुःऽशंसः ६. ६, २; १९. ४७, ६.
दुःऽस्तुतिः २०. २१, १.
दुःऽस्वप्न्यम् ६. ४६, ३; १२१, १; ७. ८८, ४; ९. २, २; ३; १०. ५, २४; १२. ८, ५; १३. १, ५८; १६. १, ११; ७, ८; १९. ४५, २; ५७, १; २; ४; ५.
दुःऽस्वप्न्यात् ४. ९, ६; ६. ४६, २; ७. १०५, १; १६. ५, ३; ४; ५; ६; ७; १०; ६, २.
दुःऽहार्दः २. ७, ५; ४. ९, ६; १०. ६, १; १४. २, २९; १९. २८, २; ५; ७; ९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९; ३२, ४; ६; ३९, ३; ४५, १; २.
दुःऽहार्दम् ८. ३, २५.
दुःऽहार्दान् १९. २८, ६; ८.
दुःऽहितान् ४. ३६, ९.
दुःऽहृणायुः ७. ८२, २.
दुःऽहृणायून् १८. १, ६.
दुग्धम् १०. ६, ३१; १०, ३०; ३१; १४. २, १४; २०. ८७, १.
दुग्धस्य ७. ७७, ५.
दुग्धा ८. ९, १; १२. ७, १२.
दुघानाम् २०. ९१, ६.
दुच्छुना ५. १९, ८; ६. ४, ३.
दुच्छुनाम् ५. १७, ४; ६. १२६, २; १२. १, ४९.
दुच्छुने १०. १, २४.
दुदुहे ८. ९, २४; १८. १, १८.
दुदुहे २०. २२, ६; ९२, ३.
दुद्रोहिथ ५. ३०, ३.
दुधिता २०. ७७, ४.
दुधुवे १२. १, ५७.
दुध्र २०. ३६, ४.

दुध्रः २०. ३४, १८.
दुनोति ५. १७, ४; १८, ४.
दुन्दुभयः ५. २१, ९.
दुन्दुभिः ५. २०, १; ६. १२६, ३; १२. १, ४१.
दुन्दुभिना ५. ३१, ७.
दुन्दुभे ५. २०, ४; ६^{२}; १०; २१, १^{२}; ४; ५; ६; ६. १२६, १; २.
दुन्दुभेः ५. २०, ५.
दुन्दुभौ ५. ३१, ७; ६. ३८, ४.
दुन्वन्ति ९. ४, १८.
दुरः २०. ७६, ३.
दुरः २०. २१, २^{३}.
दुरदभ्ना १२. ४, ४; १९.
दुरस्यतः ४. ३६, ४; १०. ३, १.
दुरस्यति १. २९, २.
दुरस्यतीः ७. ११९, २.
दुरस्यवः ५. ३, २.
दुरस्यात् ४. ३६, १.
दुराहा ८. ८, २४.
दुरोणे ५. २, ६; १२, १; ७. १८, ३; ७७, ९; २०. ३३, ३; १०७, ९.
दुरोषासः २०. ११६, १.
दुर्णामऽचातनः १९. ३६, १.
दुर्णामऽचातनम् ८. ६, ३.
दुर्णामऽहा १९. ३६, ३.
दुर्निहितऽएषिणीम् ११. ११, १५.
दुर्यान् १४. २, ५.
दुर्वः २०. ६८, ५; १२२, ३.
दुश्च्यौ ३. ९, ५.
दुस्तनो इति दुःऽतनो ४. ७, ३.
दुस्तरम् ६. ४, १; २०. २०, ३; ५७, ६; ६७, २^{२}.

दुस्तरा २०. ९४, ६.
दुस्तराः २०. ५१, ४.
दुहन्ति ५. १७, १७; १८. ४, ३०.
दुहाताम् १२. १, ३६.
दुहाते इति ९. १, ७.
दुहाथाम् ४. २२, ४; १३. १, ५.
दुहानः ४. ११, २.
दुहानम् ११. १, ३४; १८. ४, ३६.
दुहाना ७. ८४, ३; ८. ९, २४.
दुहानाः ३. १६, ७; ४. २१, १; १८. ४, ३४; ३९.
दुहाम् ७. ७७, ८; ९. १५, ५.
दुहाम् ३. १०, १; १७, ४; ४. ३९, २; ४; ६; ८; ९. ४, २१; १२. १, ७; ९; ४५.
दुहितः १९. ४७, ५.
दुहितरः २. १४, २.
दुहितरौ ७. १३, १.
दुहिता ३. १०, १३; ५. १३, ८; ६. १००, ३; १३३, ४; ९. १, ४; २, ५; १४. २, ६०.
दुहिताऽइव १०. १, २५.
दुहितुः ९. १५, १२.
दुहित्रे ३. ३१, ५; ६. १३७, १; १८. १, ५३.
दुहे ४. ११, १२^{३}; १०. १०, २७; १८. १, ३२.
दुहे ४. ११, ४; ६. ९१, २; ८. ११, ९; ९. ५, २४; १०. ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १२. ४, १८; ३५; ३६; ३९; २०. २७, ३.
दुह्यते ७. ७७, १.
दुह्यन्ते ७. ७७, २.
दुह्यमाना १२. ७, १२.

दुहताम् ७. ८७, ६; ८. ७, १२; १०. ९, १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १२. १, १६.
दुहृते ९. १४, ५; १८. ४, २९.
दुहाम् ३. २०, ९².
दुहाम् ८. ७, २७; १८. ४, ४; ५.
दुहे २०. १४२, ४.
दुहे १०. १०, ३२.
दूतः १. ७, ६; ३. १, २; २, १; ४, ३; ४. १३, ३; ५. १२, १; ६. २७, १; १८. २, २७; ४, ६५.
दूतम् १८. ३, ६६; २०. १०१, १.
दूताः ८. ८, १०.
दूताय ५. १७, ३.
दूतौ ५. ३०, ६; ६. २९, २; १८. २, १३.
दूनाः २. ३१, ३.
दूरके १०. ४, ९.
दूरतः ४. ३८, ५.
दूरम् ३. १५, ४; ६. ५९, ३; ९७, २; ७. ४३, १; ८. ७, १४; ९. २, १७; १८; ५, ७; ११; ११. १, २९; २, २५; १२. २, ४; ७; ८; १४; १९. ४४, १०; ५६, ६; २०. ७४, ६; ८९, ७.
दूरात् ५. १८, ९; ६. १२६, १; ७. ४६, १; १२.-२, १४; १९. ५२, ३.
दूरे ३. ३, २; २३, १; ४. २८, २; १०. ८, १५².
दूरेऽअन्ता ४. १६, ३.
दूरेगव्यूती इति दूरेऽगव्यूती ४. २८, ३.
दूर्वाः ६. १०६, १.
दूर्शानि ८. ६, ११.
दूर्शेभिः ४. ७, ६.
दूर्षणः ३. ९, ४.
दूर्षणीम् ४. ६, २.
दूषयत ६. १००, २.
दूषयन् ४. २९, ७; ८. ५, २.
दूषयन्ति ८. ४, ९.
दूषयिष्यामि ३. ९, ५.
दूषिः २. ११, १.
दूषीकाः १६. ६, ८.
दूष्या १. २३, ४.
दूष्याः २. ११, १.
दृंह ६. १३६, २; १३७, ३.
दृंहणाय ६. १३६, १.
दृंहत १९. ५८, ४.
दृंहतु ६. ६९, ३.
दृंहन्तम् १२. २, ९.
दृंहऽस्थिरः ११. ९, ४.
दृंहात् १२. ३, २४.
दृंहितानि २०. २८, ३; ३९, ४.
दृक्षसे २०. ४०, १; ७०, ३.
दृढः ११. ९, ४.
दृढम् ५. ३०, १.
दृढा ९. ३, १०.
दृढाः ११. ७, ११.
दृढान् ९. ३, ३.
दृतिम् ७. १९, १.
दृतेःऽइव ६. १८, ३.
दृशन् ८. ४, २४.
दृशये १८. २, १३; ४६; १९. १०, ५.
दृशे १. ६, ३; २. १, ५; ७. २३, १; ११. ११, १; १५; २२; २४; १२. २, १८; १३. २, १६; २०; २०. ४७, १३; १७.
दृशेऽईव ४. ३७, ११.
दृशेम १. ३१, ४.
दृश्यते ७. १०६, १.

दृश्यते १०. ८, २५.
दृषत् २. ३१, १.
दृषदा २. ३१, १; ५. २३, ८.
दृषदाऽइव ८. ४, २२.
दृष्टः ५. २३, ७.
दृष्टम् २. ३१, २.
दृष्टान् ५. २३, ६; ८. ८, १५.
दृष्ट्वा ४. ३६, ६; १२. ३, २९.
दृह्ला २०. ३६, ६; १२४, २.
दृह्लाः २०. ३५, १४.
दृह्लानि २०. २८, ३; ३९, ४.
देयम् ९. ५, ७.
देयाम् १२. ४, १०.
देव ५. २७, १०; ६. ३, ३; ७९, ३; ९९, ३; १२५, ३.
देव १. ७, १; १८, २; २०, १; २५, २; ३; २. २, १; ३. २०, ५; ४. ३९, १०; ६. १९, ३; ५१, ३; १२३, ५; ७. १२, १; १९, ३; १०२, ३; ११. २, ३१; १३. १, ३२; ५८; २, २३; ३०; १८. ३, ४२; ४, ६५; ८८; २०. ४७, २०; ५८, ३; ४; ११८, २.
देवऽअसुराः ६. १४१, ३.
देवऽअसुरेभ्यः ४. १०, ५.
देवऽआञ्जन १९. ४४, ६.
देवऽईषितात् ८. ७, २.
देवऽएनसात् ६. १११, ३; १०. १, १२.
देवः १. १८, ३; २८, १; २९, ३; ३१, ३; २. ३४, ३; ४; ३. १३, ४; १६, ५; २१, ३; ४; २४, २; ४. १, ७; २, ६; ३, १; २०, ४; ३२, २; ५. ३, ९; ११, ११; १२, १; १०; २५, ४; २६, २; २७, २^{2}; ३; २८, ११; ६. १, ३; ५८, १; ६१, १; ८५, १; ८८, २; ९२, ३; १३३, १; ७. १५, ४; ६५, १; ११४, ५; ११५, ३; ८. ३, १६; १४, ३; ९. २, १४; १०. २, ५; ८; १३; १४; ३, ५; ८; ११; ८, २४; २८; ११. ८, ४; ७; ११, ४; २५; १२. २, ८; १३; ७, १०; १३. १, २०; २४; ४०; २, ८; ९; २६; ३०; ३, १५; १४. १, ४९; २, २४; ३६; १५. ५, ९; १८. १, ५; २९; ३०; ३६; २, ५५; ४, ३१; ४८; १९. १०, ६; १०; ११, ३; २६, ४; ३१, ८; ३३, १; ३९, १; ५३, २; ५४, ५^{2}; ५९, १; २०. २, ४; २७, ४; ३४, १; ३६, ११; ६७, ३; ९०, ३; ९५, १.
देवःऽइव १०. ८, ४२.
देवऽकामः ७. ५२, ६; २०. ८९, ९; ९६, ३.
देवऽकिल्बिषात् ६. ९६, २; ७. ११७, २; ८. ७, २८.
देवऽकृतम् ५. १९, १०.
देवऽकृता ५. ७, ३; १४, ७; १२. ४, ११.
देवऽकृताः १२. १, ४३; १९. ३५, ५.
देवऽकृते १४. १, ६३.
देवकृते इति देवऽकृते ६. १३८, ४.
देवऽकोशः १०. २, २७.
देवऽगोपा ७. २१, ५; १९. ११, ३.
देवऽगोपाः २०. २१, ११.
देवऽजन ११. ११, ५; १२, ५.
देवऽजनाः ११. ११, २; २६.
देवऽजनाः ६. १९, १; ९३, १; ९. १२, १६; ११. ७, २; १५. ३, १०.
देवऽजनेभ्यः ६. ५६, १; २.
देवऽजाः ९. १४, १६; १०. ६, ३१.
देवऽजाता २. ७, १.

दे॒वऽजा॑तेन १९. ३२, ७.
दे॒वऽजा॑मिः २०. १२, २.
दे॒व॒ऽजा॒मी॒नाम् ६. ४६, २; १६. ५, ८; ८, ९.
दे॒वऽजू॑तम् ७. ९०, १.
देव॑ऽजूते ३. १८, २.
दे॒वऽजू॑तैः ५. १८, ८.
दे॒वता॑ ४. १, ५; ७. ८७, १; १०. ८, २५; ३१; २०. ५०, २; १४३, २.
दे॒वता॑ः १०. ६, १७; २९; ११. ९, ४; १०, १९; ३०; ३२; १२. ३, १६; ३५; १५. ६, २२; १९. ४, ४; २७, १०.
दे॒वऽता॑तये २०. ११८, ३.
दे॒वता॑नाम् ४. १४, ५; १५. ६, २३.
दे॒वता॑भिः ८. ८, २१; ११. १, २२; १२. ३, ३३.
दे॒वता॑भ्यः १२. ३, ३८; ४६; ४, ३२.
दे॒वता॑म् ३. २२, ३; ४. १४, १; १५. १३, १३[२].
दे॒वता॑याम् १५. १३, १४.
दे॒वता॑यै १५. १३, १३.
दे॒वता॑सु ६. ११९, २; ७. ८३, २; ११. ६, २०.
दे॒व॒ते॒ इति॑ १२. ३, १२.
दे॒व॒त्या॑ः १. २२, ३.
दे॒व॒ऽत्रा ५. १२, २; ७. ५५, ७; १२. ४, ४०; १८. ३, ४७; २०. १२, ५.
दे॒व॒ऽत्वम् २०. ६३, २; १२३, १; १२४, ५.
देव॑ने २०. १७, ५.
देव॑पत्नी॒ इति॒ देव॑ऽपत्नी ६. ११८, ३.
दे॒वऽप॑त्नीः ७. ५१, २; २०. ३५, ८.
दे॒व॒ऽपान॑ः ७. ७७, ३; १८. ३, ५३.
दे॒व॒ऽपी॒युः ५. १८, ५; १३; १९. ५७, ५.
दे॒व॒ऽपी॒युम् ४. ३५, ७; १२. ७, ४; १९. ५७, ४.
दे॒व॒ऽपी॒यून् ५. १८, ८; ११. २, २३; १२. १, ३७.
दे॒व॒ऽपी॒योः १२. १०, १४; ११, ४.
दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे १८. १, २५.
दे॒व॒ऽपु॒राः ५. ८, ६; २८, ९; १०; ११. १२, १७.
दे॒व॒ऽपु॒राम् १४. १, ६४.
दे॒वऽप्र॑सूतेन ६. १००, २.
दे॒वऽब॑न्धुम् ४. १, ७; ५. ११, ११; १८, १३; ७. २, १.
दे॒वम् ४. २५, ७; ५. १२, ९; ६. १, १; १४२, २; ७. १५, १; ५५, ७; ९. १४, १८; १०. ८, २२; ११. ८, ३; १२. २, ३३; १३. २, १६; ३, १६; ५, २; ३; ४; ५; ६; ७; ८; ६, १; ३; १५. ५, ८; १८. १, ५४; १९. २४, १; २०. ४७, १३; ९५, १; १२६, १.
दे॒व॒ऽम॒णिः ८. ५, २०.
दे॒व॒ऽम॒नु॒ष्या॑ः ८. ११, २.
दे॒व॒ऽयज॑नः १०. ५, १५; १६; १७; १८; १९; २०.
दे॒व॒ऽयज॑नम् ९. ६, ३; १२. २, ४२.
दे॒व॒ऽयज॑नाः १०. ५, २१.
दे॒व॒ऽयन्त॑ः ७. २८, १; १८. १, ४१; ३, २२; ३८; ४, ४५; २०. ७०, २; १०७, १५; १४२, ४; १४३, ५.
दे॒व॒ऽयन्त॑म् १२. ३, १८.
दे॒व॒ऽयान॑ः ११. १, २०; १८. ४, १४.
दे॒व॒ऽयान॑म् ८. १२, ६; १५. १२, ५; ९.
दे॒व॒ऽयाना॑ः ३. १५, २; ६. ५५, १; ११७, ३.
दे॒व॒ऽयाना॑त् १२. २, २१.
दे॒व॒ऽयाना॑न् ११. १, ३६; १५. ११, ३.
दे॒व॒ऽयाने॑ १२. ३, ३.

देवऽयानैः २. ३४, ५; ९. ४, ३; १२. २, १०; ४१; १८. ४, २; १९. २७, ९.
देवऽयुम् ४. २१, २; २०. २५, २.
देवऽयूनाम् ८. ९, १३.
देवयोः ४. २५, ७.
देवरः १४. १, ३९.
देवऽरथस्य ८. ८, २२.
देवऽवधेभ्यः ६. १३, १.
देवऽवन्दैः १८. ३, ४७.
देवऽवर्म १९. ३०, ३.
देवऽवाहनः २०. १०२, २.
देवऽवीतये ७. ६०, १.
देवऽवीतौ २०. ३७, ४.
देवऽसदनः ५. ४, ३; ६. ९५, १; १९. ३९, ६.
देवऽसेनाः ५. २१, १२.
देवऽसेनानाम् १९. १३, ९.
देवस्य २. ३६, २; ४. १, ६; ६. २३, ३; १३३, १; ७. १८, २; २६, २; ७३, ४; ७८, १; ९. ४, १३; १५, ९; १०. ५, १४; ८, ३२; १२. १, २०; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; १८. १, ३२; १९. ६, १६; ४९, १; ५१, २.
देवऽहितम् ७. १०२, २; १९. १२, १; २०. ६३, ३; १२४, ६.
देवऽहूतयः २०. ९४, ६.
देवऽहूतिः ५. ३, ५; १२. २, २२.
देवऽहूतिम् ८. १०, ५.
देवऽहूतिषु ५. ७, ४.
देवऽहूतौ २०. ९०, २.
देवऽहूत्याम् ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
देवऽहेडनम् ६. ११४, १.
देवऽहेतिः ११. २, १२; १२. ८, २.
देवऽहेतिम् १०. १, २३; ११. २, १९.
देवऽहेत्याः ८. १, १२.
देवा ६. ३, ३.
देवा २०. १४०, १.
देवाः ४. १३, १[२]; ६. २७, १; १२३, २; ३[२]; १३०, १; २; ३; १३१, १; २; ७. १०२, ७; १९. ७०, १.
देवाः १. ९, १; ११, २; १३, ४; १८, २; १९, ४; ३०, ४; ३३, ३; ३५, ४; २. १, ५; ९, ४[२]; १०, ८; १३, ४; ५; २९, ५; ३५, ५; ३. ३, २; ५; ४, ४; ५, ३[२]; ८, ४; १०, २; १२; १९, ५; ६; २२, १; ३; २६, १; २; ३; ४; ५; ६; ३०, ४; ३१, १; ७; ४. २, १; ८, २; ११, ६; १३, ४; १४, १; १६, १; १९, ४; २३, ६[२]; ३०, २; ३५, ७; ३६, ५; ५. ३, ३; ४; ५; ९; ४, ३; ४; ८, ३; १२, ११; १७, ६; १०; १८, १; १९, १२; १३; १४; २१, ७; २५, ९; २७, १२; ६. ३०, १; ४७, २; ६१, १; ६४, १; ८५, १; ९५, १; २; १००, १; २; १०९, १; ३; १११, ४; ११२, १; ११३, १[२]; ३; १३२, १; २; ७. ५, १[२]; ३; ४; ५; ६, १; १७, १; १८, ३[२]; २५, १; ३६, १; ७३, २; ८४, १; २; ८६, ६; ९४, २; ११४, २; १२३, १; ८. १, २; ७; २, २१; २७; ३, १४; ५, ५; ६; १०; १४; १९; ८, १३; १०, ५; ११, ७; १२, ५; १४, १; ४; ९. १, ५; १५;

२, ७[२]; १३; १७; १८; १९; ४, १५; १८; २०; ५, १३; १०, २; १५, १८; **१०.** २, ४; ३, २; ५; ५, ४७; ५०; ६, १६; ३२; ७, १३; २३; २४; २५; २७; ३८; ३९; ८, ३४; ३५; ४०; ९, ९; १२; १०, ५; २६; ३४; **११.** १, २; १०; ३३; ३७; २, २८; ३, २१; ६, ११; ७, १; २; ३; ५; ८; १९; २३; २४; ८, १२; १३; १८[२]; २२; ९, २३; २४; २५; २६; २७[२]; १०, ३; १०; १३[२]; १७; १८; २९; ३१; १२, ११; १२; १४; १५; २७; **१२.** १, ५; ७; ५३; २, १७; ३, ३२; ३८; ५०; ४, २०; २२; २४; २८; ४१; ४२; ४९; ५०; **१३.** १, ७; १३; २५; ३५; २, १३; ३, १२; २३; २४; ४, १३; ५, ८; **१४.** १, १५; ३२; ५०; २, १०; ३२; ५३; ५४; ५५; ५६; ५७; ५८; **१५.** २, २; ३, १; ६, २२; १७, ८; **१६.** ६, ११; **१८.** १, ३१; ३२; ३५; ३६; ४७; ३, १०; ११; २२; २४; ५३; ६८; ४, २; २५; **१९.** ४, ४; ६, १०; ११; १५; ९, ११[२]; १२[२]; १४[२]; ११, २; १९, १०; २०, ३; ४; २४, १; २७, ६; ७; ३०, २; ३४, ६; ३५, १; २; ४१, १; ४६, ४; ५६, ४; ५८, ५; ६; **२०.** १८, ३; ६२, ७; ६३, १; २[२]; ९२, ८; १२४, ४; ५[२].

देवाः **१.** ९, २; ३०, १; २; ३; ३१, २; **२.** १२, २; २८, ५; २९, १; ३४, २; **३.** ९, १; १५, ५; ६; **४.** १३, १[२]; १८, २; २७, ६; **५.** ८, ३; १४, ३; १७, ५; **६.** ७, ३; २७, २; ३; ५५, १; ५६, १; ६५, २; ७१, ३; ९३, ३; ११४, १; ३; ११५, १; ११८, ३; **७.** १०२, ४; **८.** १, १८; ४, ११; **९.** ४, ७; **१०.** ७, २३; **१९.** २७, ११; १२; १३; ५९, २; ७२, १.

देवाःऽइव **३.** ९, ४; ३०, ७; **६.** ८०, २.

देवाच्यां **२०.** ६७, ३.

देवान् **३.** ४, ६; १०, ११; १५, ५; २१, ८; **४.** २१, ३; ३४, ३; **५.** १२, १; **७.** ५, ३; ३९, ३; १०२, ३; ११४, ७; **८.** ४, १४; ८, १५; ९, २४; १२, ५; १४, १; **१०.** २, २२; २३; ७, २७; ८, १८; ९, ११; १०, ६; **११.** १, ४; ७, २; ८, १९; २०; ११, २४; १२, ९; **१२.** ३, ५३; ४, १०; ३१; ५३; **१३.** १, ४०; २, ३८; ३, १४; **१४.** २, २५; **१५.** १४, १९; **१८.** १, ३०; ३३; ४७; **१९.** ५६, ३; ६३, १; **२०.** १३, ४; ३४, १; ६७, ५; १०१, ३; १३७, ४.

देवानाम् **१.** १०, १; ३५, २; **२.** १, ३; २८, २; ३४, २; **३.** ५, १; १०, ७; १६, ४; **४.** १, ३; १०, ७; ११, २; १३, ३; १४, ५; ३०, ३; ३९, ९; **५.** ५, १; ७, ४; १२, ३; १०; ११; १७, ५; २८, ११; ३०, १७; **६.** ४६, १; ४७, २; ८५, २; ८६, ३; १००, ३; १०८, २; **७.** ५, २; ८, १; ४८, १; ४९, २; ५१, १; ५५, १; १०२, २; ११६, १; **८.** २, ९; १०, ५; **९.** ३, ७; ४, ५; १२, ६; १४, ६; **१०.** २, ३१; ४, १; **११.** १, ५[२]; ७, २३; **१२.** २, ४४; ४, २; १२; १७; २१; २९; **१३.** १, २७; २, १५; २०; २५; ३४; ३५; ३, १९; २१; **१४.** १, ३३; २, ६९; **१५.** १, ५; २, ४; ६,

२३; १६. ७, २; १७. १, २; १८. १, ९; २५; २, ५; ३, ४; ७; २३; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ५३; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४; १९. ३, ४; १०, ३; ११, ५; १३, १०; २७, ९; ३३, ४; ४६, ४; ५७, ३; ५८, ६; ५९, ३; २०. ४७, १७; ५८, ४; ६७, १; १०७, १३; १४.

देवार्य ४. २, १; २; ३; ४; ५; ६; ७; ८; ५. ११, ११.

देवांसः ६. ११४, १.

देवासः ३. २२, २; ७. २९, १; २०. २५, २; ११०, ३; १३७, ५.

देवासः १. २६, १; २. १२, ५; ५. ३, ६; ८. ५, २१; १२. ३, ३७; १९. १३, ११; २७, ११; १२; १३.

देवि १. १३, ४; २. २५, ४; ४. ४, ६; २०, १; २; ७. २१, २; ६; ४८, १; ३; ७०, १[२]; ९. ३, ७; १०. ९, ७; २५; १२. १, ५५; ३, ११; ११, २; ४; १८. १, ४३; ४, ४७; २०. १४२, १; २.

देवी २. २५, १; ३. १२, ५; २०, ३; ५. २३, १; २५, ६; ६. ३, २; ३८, १; २; ३; ४; ६३, १; ८९, ३; ९४, ३; १३६, १; ७. ४८, ३; ९. ४, २; १०. ५, ४३; ८, ३०; ९, ११; १०, १२; ११. १, ८; १२. १, ४४; १६. ६, ५[२]; १८. १, २६; २, २५; १९. ७, ४; ९, ३.

देवी इति ४. २६, २.

देवीः ५. १२, ५.

देवीः १. ४, ३; ६, १; २. १०, ४; ३. ४, २; २०, ३; ५. १२, ८; १७, १; २७, ७; ९; ६. २३, १; २४, १; ५१, २; ५९, २; ७. ५१, २; ८७, ६; ११७, १; ९. ५, १५; १०. ५, ७; ९, २७; ११. ८, ११; २२; १४. १, ४५; २, ९; ४५; १८. ४, ३९; २०. ११, ८; २५, २.

देवीः २. २, ४; ३. १३, ३; ५. ३, ७; ७. ५१, १; ७९, २; १०. ५, ८; ९; १०; ११; १२; १३; १४; १६. १, १३.

देवीम् ३. ८, २; १५, ३; ७. ४९, १; १३. २, ५; १९. ४, २; २०. १०७, १५.

देवीषु ४. २, ६.

देवऽकामा १४. २, १७; १८.

देवृषु १४. १, ४४.

देवे ८. ४, १८.

देवेन १. १, २.

देवेभिः ३. १२, ५; ४. १४, २; ७. ७९, २; २०. ६, ३.

देवेभ्यः ४. २३, २; ५. ४, ७; ८, १; १२, ४; ५; २७, ११; ७. ३९, २; ८६, २; ८९, २; ८. १२, ६; ९. ३, २५; २६; २७; २८; २९; ३०; ३१; १०. ६, ५; २२; २३; २४; २५; २६; २७; २८; ११. ७, १९; १०, ३; १०; १२. १, २२; २, ८; ५०; १४. १, २४; २, ४६; १५. २, ३; १८. २, ५३; ५४; ३, ४१; ४, ५१; १९. ५४, ४; २०. ११, ७; ८७, ३.

देवेषु ३. १७, १; ४. २८, ५; ५. २७, २; ६. २१, २; २८, २; ५८, २; ७. २१, १; ५६, १; ७७, ३; १०२, ८; १०८, १; ९. ४, ११; ५, १७; ११, १०[२]; १०. ३, २५; १२. ४, ६; १२; १३. १, ६०; १५. १२, ६; १०; १८. १, २६; १९. ३, ३; ६२, १; २०. ८०, २; १२६, १२.

देवैः २. ४, ४; १६, ४; ३. १७, ९; ४. ९, १; ५. १७, ११; २९, ३; ६. १२, २; १२६, १; ७. ८१, १; १०३, १; १२. १, ५१; ३, १५; ४, २४; १४. २, ४१; १८. ३, २८; ४८; ४, १०; १९. १७, १०; ४०, १; २०. ९१, १२.
देवौ ३. २९, ६.
देव्या २०. २१, ९; १४२, १.
देव्याः १४. १, ४७; ६३.
देव्याम् ६. १३६, १.
देशोपऽसर्गाः १९. ९, ९.
देष्ट्राय १४. १, १४.
देष्ट्री १०. १०, १७; ११. ६, १२.
देहि ५. ११, ९.
देहि ६. १०७, १; २; ३; ४; १४. १, २९; १८. ३, ७०; १९. ४८, २; ५०, ७.
देहिनः १९. २०, ३.
दैवः ७. १२, १.
दैवः ४. १६, ८.
दैवऽजनीः १०. २, २२; २३.
दैवम् ५. ४, १०.
दैवाः ५. २७, ९.
दैवाः ५. ३, ५; ११. १, १६; २५.
दैवात् ४. २६, ७.
दैवानाम् ११. १, २३.
दैवाय १६. २, ६.
दैवीः १. १९, २; ३. २२, ६; ५. ३, ६; ६. ९८, २; ९. ४, ९; ११. ६, १६.
दैवीः १२. ३, ३२.
दैवीनाम् २०. ११, २.
दैवीम् ५. २०, ४; ६. ६१, २; ७. ७, १.
दैवैः ५. २९, २.
दैव्यम् ६. ४, १; ७. ११०, १.
दैव्यस्य २. २, २.
दैव्या ५. १२, ७; ८. १, ३.
दैव्याः ६. ४१, ३; ८. ९, २१; १७. १, २८.
दैव्यायाः ५. २९, ११; ८. ३, १८.
दैव्ये ६. ५१, ३.
दैव्येन २. १२, ४; ४. २७, ६; ७. ५४, २; ८३, २; ८. ३, २१; १९. २७, ६.
दोग्धारः १०. १०, ५.
दोर्धतः १२. १, ५८; २०. १०७, ३.
दोषणिऽश्रिषम् ६. ९, २.
दोषणी इति ९. १२, ७; १०. ९, १९.
दोषण्यम् २. ३३, २; २०. ९६, १८.
दोषसः १६. ४, ६.
दोषा १६. ७, ९.
दोषो इति ६. १, १.
दोहसा १८. १, १८.
दोहः ४. ११, ४.
दोहत् ७. ७७, ७; ९. १५, ४.
दोहते २०. ७, ३.
दोहम् ५. १७, १७.
दोहाः ४. ११, १२; ८. ९, १५.
दोहान् ४. ११, ९.
दोहेन २०. ८९, २.
दौःऽजीवित्यम् ४. १७, ५; ७. २४, १.
दौःऽभाग्यैः १४. २, २८.
दौःऽस्वप्न्यम् ४. १७, ५; ७. २४, १.
द्य ६. १०३, २; ३; १०४, २.
द्यताम् ६. १०४, ३.
द्यति १२. ७, ४.
द्यतु ११. १२, ६.
द्यवि ६. ४९, ३; १२. २, १८; १८. ४, ८८.
द्यविऽद्यवि २०. ५७, १; ६८, १.
द्याम् १. २, ४; ४. १, ४; २, ७; ११, १;

१४, ४; १६, ४; ३०, ७; ६. ६०, ३; ६१, २; ३; १२०, १; १२६, १; ७. १, २; ७, १; ९. ३, १५; ५, १५; १४, १३; ११. १, ३७; १३. १, ४३; ४५; २, २२; ४५; ३, २६; १८. १, ६१; २, ४७; ४९; ३, ५; ४, ५; ६; २८; १९. ६, २; २०. ११, ८; १६, ११; २९, ४; ३४, २; १३; ४७, १९; ९१, १०; ९३, ६.

द्या॒म॒सि॒ ६. १०४, १.

द्या॒मि॒ ६. १०३, २.

द्याम्ऽई॑व ६. १२, १; ६९, ३; ७. १००, १; १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५.

द्याव॑ः २०. ८१, १; ९२, १९; २०; १४३, ८.

द्यावा॑ १८. १, २९; २०. ३४, १४; ३५, १४.

द्यावा॑पृथि॒वी इति॑ २. १, ४; १०, १; २; ३; ४; ५; ६; ७; ८; १२, १; २९, ५; ३. ४, ५; १५, २; ३१, ४; ४. ६, २; २६, ७; ३०, ५; ५. १२, ९; २३, १; २४, ३; ६. ३, २; ८, ३; ५५, १; ५८, १; ६२, १; ९४, ३; ७. ३१, १; ८७, ४; ५; ११७, १; ८. २, १४; ५, ३; ६; १८; ८, २१; २२; ९. २, २०; ४, १०; १०. ७, ३५; ८, ३९; ११. ३, २; ९, २; १३. १, ५; ६[२]; ७; ३७; २, २६; ३५; ३, १; ४; १४. १, ५४; २, ४५; १८. १, २७; २८; १९. १०, ५; १४, १; १५, ५; २०, ४; ४९, १; ५८, ३; २०. ३५, ८; १०७, १४; १३७, १०.

द्यावा॑पृथि॒वी इति॑ २. १२, ५; १६, २; ४. २६, २; ३; ४; ५; ६; ५. १४, १२.

द्या॒वा॒पृ॒थि॒वी॒ इति॑ २. २९, ४; ४. २२, ४; २६, १; ६. ४०, १; २०. ९१, १२.

द्यावा॑पृथि॒वीः ८. ९, १६.

द्यावा॑पृथि॒वीभ्या॑म् ५. ९, ७; ७. १०७, १; ११. ४, २; १९. १७, ५.

द्यावा॑पृथि॒वीऽर्व॑न्तम् १९. १८, ५.

द्यावा॑पृथि॒व्योः ६. ५८, २; १६. ८, २६.

द्यावा॑भू॒मी इति॑ १८. १, ३१.

द्यु॒क्षम् २०. ९, २; ४९, ५; ९२, १३.

द्यु॒क्षाय॑ २०. ६५, २.

द्यु॒क्षास॑ः २०. ६, ५.

द्यु॒ता १८. ४, ५९.

द्यु॒त्तम् ४. १२, २; १२. ३, २२.

द्यु॒ऽभिः॑ ६. ३१, ३; २०. २१, ४; ४८, ६.

द्यु॒ऽमत् २. ३५, ४; ५. २०, ६; ६. १, १.

द्यु॒ऽम॒तः १८. १, ५७.

द्यु॒म॒त्ऽत॒म॒ २०. २१, ३.

द्यु॒मत्ऽत॑मा ५. २७, १.

द्यु॒ऽमन्त॑ः ४. १, ५; १८. १, ५७[२].

द्यु॒ऽमन्त॑म् ४. ३१, ४; १८. ४, ८८.

द्यु॒ऽमान् १८. १, २४; ५७.

द्यु॒म्नम् ६. ३५, ३; २०. २०, ३; ५७, ६; ७१, १४; ७६, ४.

द्यु॒म्ना २०. ८९, ६.

द्यु॒म्नानि॑ ७. ७७, १०; २०. ६, ७; ६७, २.

द्यु॒म्नाय॑ २०. १४२, ५.

द्यु॒म्निन॑म् २०. २०, १; ५७, ४.

द्यु॒म्नी २०. ३०, ३; ४७, २; १३७, १३.

द्यु॒म्नेषु॑ २०. १९, ७.

द्यु॒म्नैः १३. २, ३४; २०. १०७, १३.

द्यु॒ऽरा॑जयः १९. २०, ३.

द्यु॒वम् ७. ५२, ९.

द्यु॒वे ७. ११४, ५.

द्यू॒ते १२. ३, ४६.

द्यू॒न् १८. १, २४.

द्योः २०. १६, ४; १२३, २.
द्योतताम् ४. १५, ८.
द्योतते १३. ७, १३.
द्योतनिम् १८. १, ३५.
द्यौः २. १२, ६; १५, १; २८, ४; ३. ९, १; २३, ६; ४. २, ४; १६, ३; ३९, ६; ५. २८, २; ६. ३, १; ४, ३; ६, ३; ४४, १; ५३, १; ७७, १; ८८, १; १००, १; १२०, २; ७. ६, १; ८. १, १२; १७; ७, २; ९, ६; ९. १, २१; ५, २०; १२, २; १५, १२; १०. २, २४; २५; ७, ३; १२; ८, २; १०, ४; ३०; ११. २, १०; ३, ११; २०; ७, ४; १२. १, ५३; ३, २०; १३. ७, ५; १४. १, १; ६; १०; २, ७१; १५. ४, १८; १०, ६; १७, ३; १८. १, ५; २, ४८; १९. ६, ८; ९, १; १४; ५४, २; २०. १५, ५; ७१, १; ७६, ६; ९१, ५; ९४, ८; १०६, २.
द्यौःऽइव ६. १४२, २.
द्यौऽसंशितः १०. ५, २७.
द्रः ११. ९, ३.
द्रप्सः १८. ४, २८; २०. १३७, ७; ९.
द्रप्सम् १८. १, २१; ४, २८; २०. १३७, ८.
द्रप्सऽवान् १८. ४, १८.
द्रव २०. ५, ५.
द्रव ३. ४, ५; ४. १२, ६; ७. ७७, ६; १०. १, २१; ९, ८; ९; १८. २, ११; २३; ३, ८.
द्रवतः १०. ७, ६.
द्रवतु ९. १३, ११.
द्रवन्तु २०. ७७, १.
द्रवन्तु ९. १३, १३; १४; १५; १६; १७; १८.
द्रविणःऽदः २०. ६७, ७.
द्रविणःऽदाः १९. ३, २; २०. २, ४.
द्रविणःऽदेषु २०. २१, १.
द्रविणम् २. २९, ३; ४. ३६, ४; ५. ३, ५; ७. ५, २; १८, ४; ६९, १; १०. १, १०; ५, ३७; ३८; ३९; ४०; ४१; १२. ६, २; १३. १, ३४; १४. २, ७४; १८. ३, १; १९. ७१, १; २०. ९१, ७.
द्रविणस्य १२. १, ४५.
द्रविणा ४. ३०, ६; ७. ८३, २; १८. ३, १४.
द्रविणानि ७. ८७, १; १९. ३१, ६; ११.
द्रविणे ६. ४७, १; १२. १, ६.
द्रविणेन ९. २, १५; १०. ६, २६.
द्रवित्नुम् १८. १, २५.
द्रष्टारः १९. ४७, ३.
द्रष्टुम् ११. ७, ३.
द्राघीयः ८. २, २; १२. २, ३०; २०. २१, ११.
द्रातु ६. ६६, १.
द्रान्तु ६. १२९, १; २; ३; १४. २, ११.
द्रापिम् १३. ३, १.
द्राहि ६. १४, ३.
द्रुग्धम् १. १०, २.
द्रुऽघनः ७. २९, १.
द्रुतः ६. ५१, १.
द्रुपदात्ऽइव ६. ११५, २; ३.
द्रुऽपदे ६. ६३, ३; ८४, ४; १९. ४७, ८; ५०, १.
द्रुवयः ५. २०, २.
द्रुवये ११. १, १२.

द्रुहः २. १०, १; २; ३; ४; ५; ६[२]; ७; ८; ७. ८२, २; १०८, १; ८. ४, ७; १६. ६, १०; १९. १५, २.
द्रुहः ९. ५, ४.
द्रुहन् २०. ६९, ८.
द्रुहुः ८. ४, ७; १७.
द्रुह्वणः ४. २९, १; २.
द्रुह्वणे २०. ३६, ८.
द्रोघऽवाचः ८. ४, १४.
द्रोणऽकलशाः ९. ६, १७.
द्रोणऽसाचम् २०. ९४, ४.
द्रया १९. ७, ५.
द्रयानि ४. २४, ७.
द्रयाविनः १. २८, १.
द्रयोः २०. २५, ३.
द्वा ९. १४, २०; १८. २, ३३; २०. ७२, २; ७५, १.
द्वाः ९. ३, २२.
द्वादश ४. ११, ११; १०. ८, ४; ११. ८, २२.
द्वादशऽअरः ४. ३५, ४.
द्वादशऽअरम् ९. १४, १३.
द्वादशऽअहः ११. ९, १२.
द्वादशऽअहेन ९. ९, ८.
द्वादशऽआकृतिम् ९. १४, १२.
द्वादशऽऋचेभ्यः १९. २३, ९.
द्वादशऽधा ६. ११३, ३.
द्वाभ्याम् ७. ४, १; २०. ९१, ४.
द्वारः ५. २७, ७.
द्वारः ५. १२, ५.
द्वारम् १४. १, ६३.
द्विऽआस्या ५. १९, ७.
द्विऽआस्यात् ८. ६, २२.
द्विः ५. २, ३; २०. २१, ९; १०७, ६.
द्विक्षत् ३. ३०, ३.
द्विक्षत १२. १, १८; २३; २४; २५; २, ३३.
द्विजानाम् १९. ७१, १.
द्विऽजिह्वा ५. १९, ७.
द्विता २०. ९२, १७; १०५, ५.
द्वितीयः १३. ५, ३; १५. १५, ४; १६, २; १७, २.
द्वितीयम् १०. ८, १७.
द्वितीया ११. ७, ४.
द्वितीयाम् ११. १, २४; १५. १३, ३.
द्वितीये ६. ४७, २; ९. १, १२.
द्वितीयेभ्यः १९. २२, ९.
द्विऽपक्षा ९. ३, २१.
द्विऽपदः १३. २, २७; ३, २५.
द्विऽपदः ३. २१, २; ४. २, १; २८, १; २; ३; ४; ५; ६; ६. २८, ३; १०. २, ६; ११. २, १; १२. १, १५; १३. १, २; ३, २४.
द्विऽपदा ९. १५, २; १९. १५, २.
द्विऽपदाम् २. ३४, १; ८. २, ४; २३; १३. ३, २५; १९. ३१, ५.
द्विऽपदी ९. १५, २१; १०. १, २४; १३. १, ४२.
द्विऽपदे ६. २७, १; ११. २, २८; १४. २, ४०.
द्विऽपात् १३. २, २७[२]; ३, २५.
द्विऽपात् ६. १०७, १; २; ३; ४; ८. ८, १४; १९. ३१, ४; ३४, १.
द्विऽपादः १२. १, ५१.
द्विबर्हऽज्मा २०. ९०, १.
द्विऽबर्हसः २०. ६१, ५; ६२, ९.
द्विभागऽधनम् १२. २, ३५.

द्विऽमूर्धा **८.** १३, ३.

द्विऽराजे **५.** २०, ९.

द्विऽरात्रः **११.** ९, १०.

द्विऽवृषः **५.** १६, २.

द्विर्षः **२.** ६, ५; **४.** ३३, ७; **६.** ३४, १; २; ३; ४; ५; **१९.** १५, १; **२०.** ४३, १; ४६, २; ६७, १[२]; ९२, ११.

द्विषः **५.** ६, ४.

द्विषतः **१.** २१, ४; **९.** ७, ७; **१०.** ६, १; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १९; २०; २१; ३१; **११.** १, ६; १२; २१; **१९.** २८, १; २; ३; ५; ६; ७; ८; ९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९; ३०, ४.

द्विषताम् **५.** २०, १२; २८, १०; **७.** १४, १; २; **१९.** २८, ४.

द्विषते **५.** ३, ७; **६.** ४६, ३; **७.** १२०, १; **१६.** ६, ३; **१७.** १, ६; २४; **१९.** ५७, २; ३; ५.

द्विषन् **१.** १९, ४; **९.** ७, ७; **१७.** १, ६.

द्विषन्तम् **४.** ३५, ७; **१५.** १, ८; **१६.** ७, ६.

द्विषन्ति **९.** ५, २; **१०.** ३, ३; **१२.** ३, ४९.

द्विषेभिः **१९.** ५६, ६.

द्विष्टः **५.** १८, ५.

द्विष्मः **२.** ११, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; **३.** २७, १; २; ३; ४; ५; ६; **६.** २६, ३; **७.** ३२, १; ८६, ५; **१०.** ५, १५; १६; १७; १८; १९; २०; २१; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; **१२.** २, ३; **१६.** १, ५; ६, ४; ७, ५.

द्विष्मः **१९.** १४, १.

द्वीपिनः **१९.** ४९, ४.

द्वीपिनम् **४.** ८, ७.

द्वीपिनि **६.** ३८, २.

द्वे इति **५.** १५, २; **६.** ८३, २; **८.** २, २१; **१३.** २, २८; ४२; **१६.** १, १६.

द्वेषः **६.** ४, २; **७.** ९६, १; ९७, १; **८.** ४, २; **२०.** १२५, ६; ७.

द्वेषत् **१२.** १, १४.

द्वेषांसि **१.** २, २; **५.** २२, १; **१८.** २, ४७.

द्वेषाम **६.** २६, ३.

द्वेष्टि **२.** ११, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; **३.** २७, १; २; ३; ४; ५; ६; **७.** ३२, १; ८६, ५; **१०.** ५, १५; १६; १७; १८; १९; २०; २१; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; **१२.** २, ३; **१६.** १, ५; ६, ४; ७, ५.

द्वेष्टु **१६.** ७, ५[२].

द्वेष्मि **३.** ६, १; ३; ५.

द्वेष्यः **९.** २, १४.

द्वेष्याः **१.** २०, १; **५.** ३, ६.

द्वौ **४.** १३, २; १६, २; **५.** २३, ४[४]; **८.** ११, ६[२]; **१०.** ४, ८; **१५.** ३, ४[२]; **१९.** ४७, ५.

ध

धत्त **२.** १३, २; **१९.** २४, ४.

धत्त **२.** १३, २; ३४, २; **६.** ४१, ३; ५५, १; **७.** ८७, १; १०२, ३; **१०.** ५, ७; ८; ९; १०; ११; १२; १३; १४; **१६.** १, १३; **१८.** ३, ४३; ४, १; **१९.** २४, ४; **२०.** ३४, ५.

धत्तन **१९.** २४, १; २; ३.

धत्तम् २०. १७, १२; ८७, ७.
धत्तम् २. २९, ३; ५[2]; ४. २५, ५; २८, ६; ५. ६, ८; ७. ४३, २; ८. २, ७; ४, २; ११. ११, ३; २०. १३९, २.
धत्ताम् ३. २२, ४; ४. ३१, ७; ३६, १०; ५. २५, ३; १४. १, ५३.
धत्ते १०. ७, ४२.
धत्ते ८. १४, १२.
धत्स्व ८. ३, २; १४. १, ४५; २, ३९; १९. २४, ५.
धनऽकामः ५. १८, ५.
धनऽकाम्या १२. २, ५१.
धनऽजित् ५. ३, ११.
धनऽदाः ३. १५, १; २०, २.
धनऽपतिः ४. २२, ३; १०. १०, ११.
धनऽपते २. ३६, ६; ५. २३, २.
धनऽपालः १९. ३५, २.
धनम् १. १५, ३; ४; २. ७, ४; ३. १५, २; ५; ६; ४. ३१, ७; ३८, ३; ५. १९, ९; ६. ८१, १; ७. ५२, ६; ११४, ५; ८. ५, १६; ११. १, २८; १२. १, ४०; १९. ३१, १०; २०. ५९, ३; ८९, ५; ९.
धनम्ऽजयः ३. १४, २; ७. ५२, ८.
धनम्ऽजयम् २०. २४, ६;
धनऽसनिः १८. ४, ३८.
धनऽसाः १९. ३१, ८; २०. १०, १; ५९, १.
धनऽसातये १९. ३१, ८.
धनऽसैः २०. ९१, ७.
धनस्य १९. ३१, ९; २०. ११८, ३.
धना ५. २, ४; १९. ४९, ७; २०. ५६, ३; १०७, ७.
धनाऽइव १९. ३५, २.
धनात् १२. २, ३७.
धनानाम् ४. २२, ३; १०. ८, ४२; २०. ११, ११; ६८, ९.
धनानि ७. ५२, ७. २०. १७, १०; २७, ६; ८९, १०; ९४, १०.
धनुः ४. ६, ६; ३०, ५; ७. ५२, ९; ११. २, १२; १५. १, ६; १८. २, ६०.
धनुःऽइव ४. ४, ६; ६. १०१, २.
धनुःऽभिः ५. १८, ८.
धनूः १. १७, ४.
धने २०. ९, ३; ४९, ६.
धनेन ३. १५, ५[2]; ६[2]; ७. ३४, १; ८६, ३; ४; ५; १४. १, ४८; २, ७०; १८. ३, १७; १९. ३१, ७; ६४, २.
धनैः ५. ४, २.
धन्व ६. ३४, ३; २०. १२६, २०.
धन्व ५. ६, ४.
धन्वऽइव ७. १२२, १.
धन्वन् ५. १३, १.
धन्वनः १. ३, ९; ४. ६, ४; ५. १३, ६; ६. ४२, १.
धन्वनाम् ११. ११, १.
धन्वनि ४. ४, ७; ६. १००, २; १०१, ३.
धन्वन्याः १. ६, ४; १९. २, २.
धन्वऽसु २०. ९५, २; ३; ४.
धन्वानि ७. ४२, १.
धमत ३. २, २[2].
धमनयः ६. ९०, २.
धमनिः १. १७, २.
धमनिऽभ्यः २. ३३, ६; २०. ९६, २२.
धमनीः ७. ३६, २.
धमनीनाम् १. १७, ३.
धमन्तः १८. ३, २२.
धमन्तम् २०. १३७, ७.

धमन्तु ८. १, १९.
धमाति १८. २, २८.
धमामि ८. २, ४.
धयेत् ९. ५, २३.
धरिष्ये ५. ११, ३.
धरुणः १६. ३, ३; १८. ३, २९; ३६.
धरुणम् ४. ३२, ७; ७. ३, १.
धरुणाय ६. ९२, ३.
धरुणी ३. १२, ३.
धरुणे १२. ३, २४; ३५; २०. ९४, ४.
धरुणेषु ५. १, ६.
धर्ता ५. १, १; १२. ३, ३५; १६. ३, ३; १८. ३, २९; ३६; १९. १०, ३.
धर्तारः १८. १, २.
धर्तारा ७. ७७, ४.
धर्म ६. ५१, ३.
धर्मः ११. ९, १७; १२. ६, १.
धर्मऽकृते २०. ६२, ५.
धर्मणा ६. १३२, १; २; ३; ४; ५; ७. २६, २; १२. १, १७; १४. १, ५१; २०. ९४, १; ५.
धर्माणि ७. १५, ४.
धर्मऽधृतः १. २५, १.
धर्मऽभिः १८. २, ७.
धर्मम् १८. ३, १.
धर्माणि ५. १, २; ७. ५, १; २७, ५; ९. १५, २५.
धवात् ५. ५, ५.
धाः ५. २५, ७; ६. १२६, २; ७. १२०, २; २०. ३५, १६; १३७, १०.
धाक् ८. १, ११.
धात् २. १०, ३; २९, १; ६. ६१, १; १३. १, २०; १६. ९, २; १८. ३, ६३; ४, ५४; २०. १६, १२.
धार्तः ५. २५, १०.
धातः ७. १९, १; १२. २, २५.
धार्तवे ६. ८१, २; ७. ११, १.
धाता ३. ८, २; ४. १२, २; ५. ३, ९; २५, ४; ५; ६. ६०, ३^{३}; ७. १८, १; २; ३; ४; २०, १; ८. १, १५; ५, १८; ९. १२, १०; २१; १०. ६, २१; ११. १०, ५; ८; ९; ११, २५; १३. ४, ३; १४. १, ३३; ३४; ५९; २, १३; १८. ३, २६; ४, ४८; १९. ९, १२; १०, ३; २०, १; ३१, ३.
धातारम् ११. ८, ३,
धातु १८. १, १९; २०. १२, ६.
धातुः २. ३६, २; ११. १०, ९.
धातृऽभिः २०. ६०, २.
धात्रे ३. १०, १०; १९. ३७, ४.
धानाः १८. ३, ६९; ४, २६; ३२; ३४^{२}; ४३.
धान्यम् २. २६, ५; ३. २४, २; ४; ६. ११७, २; ८. २, १९; १९. ३१, ५; १०.
धान्यस्य २. २६, ३.
धान्याय ६. ५०, १.
धान्ये ५. २९, ७.
धापयाथः १२. ३, ५१.
धापयामः १९. ४६, ४.
धाम् ७. १०२, ८.
धाम १. १३, ३; २. १, २; ४. १, ६; ६. ३१, ३; ७. ८, १; ३०, २; ८. ९, १०; २५; २६; १५. २, ४; १२; १८; २४; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ८, ३; ९, ३; १८. १, ७; २०. १५, ३; ४८, ६; ९१, २.

धामन् ४. २९, ७.
धामनिऽधामनि १२. १, ५२.
धामऽभिः १९. ४७, १; २०. १९, ४.
धामऽशः ९. १४, १६.
धामऽसु ६. ३६, ३; ७. ७०, १.
धामानि २. १, ३; १४, ६; ७. ८८, १.
धाम्नःऽधाम्नः ७. ८८, २.
धाम्ना ५. २७, ८; १०. ५, ७; ८; ९; १०; ११; १२; १३; १४.
धायि ५. ३०, १५; १८. १, ३; २०. ३०, ४; ६०, २; ९२, १७; १०५, ५.
धारय ६. ७९, २; ८१, २; ८७, २; ७. ८७, ३; १९. ३१, १२.
धारयतम् ६. ५४, २.
धारयतात् ३. ५, २.
धारयताम् ६. ८८, २.
धारयति १०. ७, ११.
धारयतु ८. ६, २०.
धारयन् ७. २७, ५.
धारयन्तम् ७. ८३, २; ८. ४, १३.
धारयन्ति १२. १, १; १८. ३, ५२.
धारयन्तु १. ९, १[२].
धारयन्ते १८. १, ३५.
धारयन्ते १८. १, ३२.
धारया ७. ५२, ९; १०. ६, २५.
धारयातै १८. ३, २९.
धारयामः १. ३५, ३.
धारयामि ८. २, ३; १४. १, ४७.
धाराः ४. ११, ४; ३४, ५; ६; ७; ७. ८७, १; ११२, १; ९. ५, १५; १२. १, ४५; ३, ४१.
धाराभिः २०. ६, ६.
धाराम् ३. १२, ८.

धारुःऽइव ४. १८, २.
धाव १२. १०, ९; २०. ७६, ३.
धावत ४. ३७, १२; ५. ८, ४; २१, १०; ६. २, १; ८. ८, १९; ११. १२, १; १९. २७, ६.
धावतात् १९. २५, १.
धावतु ६. ९२, ३.
धावतु ३. १८, ६[२]; ५. २०, ५; १९. ४७, ७; २०. ४, २.
धावते १८. ४, ८९.
धावथ ६. ६६, २.
धावन्ति ५. २१, ५.
धावन्ति १०. ६, १४.
धावन्ती १२. ७, ७.
धावन्तु ५. २१, २.
धावन्तु ११. ११, १४.
धावमानम् १३. २, ३७.
धावसि ६. १३१, ३; २०. १२६, २.
धावात् १०. ३, ६.
धास्यवै ४. १, २.
धास्युः २. १, ४; ५. १, २.
धितऽवानम् २०. ६, ३.
धियः ९. २, २५; १९. ४२, ४; २०. ११, ५; ३५, २; ९५, ४.
धियम् ३. १५, ३; १६, ३; २०. ३५, १६; ८९, ७; ९१, १.
धिया २. ५, ४; ६. १९, १; १०. १, ८; १८. १, १८; २०. ३६, ७; ७६, ४; ८४, २; ९७, २; ११३, १.
धियाऽयवः २०. ७१, २.
धियाऽवसुः २०. ३५, १६.
धिये ६. ४, ३; ४१, १.
धिषणम् २. १४, १.

धिषणा २०. ३१, ९; १०६, १.
धिषणे इति २०. ९४, ८; ११३, २.
धिष्ण्याः २. ३९, १; ७. ६९, १.
धिष्व २०. ३६, ९.
धीः १८. १, २१; २०. ८९, ३.
धीतम् ७. ९८, ३; २०. १०, २; ९९, २.
धीतिः ११. १, ११.
धीतिऽभिः ९. १५, १७.
धीती ७. १, १; ९. १४, ८.
धीभिः ५. १२, २; २०, ८; १९. ११, २; २०. १२, ४; २५, ७; ३३, २; ९१, ८; १४२, ६.
धीमहि ७. १८, २; ७४, १; ८. ३, २२; २०. ७२, १.
धीयताम् ४. १२, ४; ७. ७२, १.
धीयते २०. ९६, ३.
धीयस्व १८. २, २०.
धीरः २. ३५, ३; ३. २१, ४; ९. २, ६; १४, २२; १०. ८, ४४; ११. ६, २४; १९. ९६, १.
धीरऽणासः २०. ११, ८.
धीरऽतरः ५. ११, ४.
धीरऽतराः १०. १, १८.
धीरम् १०. ८, ४४; २०. १२६, १९.
धीराः ३. १७, १; ११. ११, २२.
धीरासः ९. ४, ८.
धीरी ११. १, १३.
धीवानः ३. ५, ६.
धुक्षे १०. १०, ८[२].
धुक्ष्व १०. ९, १२; १८. ४, ६.
धुनऽईतयः २०. ८८, २.
धुनिम् २०. ३७, ४.
धुरम् ५. १७, १८.
धुरा ९. १४, १९.
धुरि ५. १७, १५; ९. १४, ९; १८. १, ६; २०. ७२, १.
धुर्यम् ५. १, ४.
धुवामि ३. ११, ७.
धूतस्य २०. ३३, १.
धूनु ११. २, १९.
धूनुते ५. १९, ७; १९. ३६, ४.
धूनुष्व १९. ४६, २.
धूनुहि ५. २२, ७.
धूनोति ९. ४, १३; २०. ७३, ५.
धूमऽअक्षी ११. १२, ७.
धूमः १८. ८, ५९.
धूमःऽइव ६. ८९, २.
धूमऽकेतुः १८. १, ३०; १९. ९, १०.
धूमम् ६. ७६, २; ८. ८, २; ९. १५, २५; ११. १, २; १२. ३, ५३.
धूमऽशिखाः ११. ११, १९.
धूमान् ६. ११३, २.
धूयताम् १. १४, २.
धूर्वन्तम् ८. ३, २१.
धूर्वन्तु १. १९, ४.
धृतः ९. ४, १५.
धृतऽराष्ट्रः ८. १४, १५.
धृतऽव्रतः ७. ८८, १; २०. ९४, २.
धृतऽव्रतौ ७. ६०, १.
धृता १२. १, २६.
धृताम् १२. १, १७; २७.
धृथाः ३. २५, १.
धृषत् ७. ८१, २; २०. १४, २; ५२, ३; ५७, १६; ६२, २.
धृषता २०. ३६, ६; ३७, ३.
धृषत्ऽवर्णम् ७. ७४, १; ८. ३, २२.

धृषाणः ६. ३३, २.
धृषितः ६. ३३, २; २०. १३७, ११.
धृष्णवे ७. १२१, १; १८. १, ३७; २०. ९६, ३.
धृष्णु २०. ९२, ५.
धृष्णुऽओजसम् २०. ९२, १८.
धृष्णुः ५. २९, १०; १८. २, ५८.
धृष्णुना १९. १३, ३.
धृष्णुम् १. १३, ४; २. १४, १.
धृष्णुऽया २०. २१, ७; ५१, २; ८३, २; ९८, २.
धृष्णुऽसेनः ५. २०, ९.
धृष्णू इति २०. २६, ५; ४७, ११; ६९, १०.
धृष्णो इति २०. ३७, ३; ५२, ३; ५७, १६; ७७, ७; १२२, २.
धेनवः २. ५, ६; ३. १२, ३; ४. ३९, ८; ७. ७७, २; ९. ५, २५; १८. ४, ३३; ३४; २०. ९, १; ३०, २; ४९, ४; ९२, १९; १०९, २; १२१, १.
धेनाः २०. ११, ३; १७, ६.
धेनाभिः २०. २५, ७; ३३, २.
धेनुः ३. १०, १; ४. ३४, ८; ३९, २; ४; ६; ५. १७, १८; ९. १, २२; २, ५; ५, १०; १२. १, ४५; ३, ४९; १३. १, २७; १८. ४, ३२; २०. २७, ३.
धेनुका ३. २३, ४.
धेनुऽभ्व्यः ६. ५९, १.
धेनुम् ३. १०, २; ७. ७७, ७; १०९, १; ९. ४, २१; ५, २९; १५, ४; ११. १, ३४; १८. २, ३०; ४, ३०.
धेनुम्ऽइव १३. २, ४६.
धेनू इति ४. २२, ४.
धेनूनाम् ४. २७, ३.

धेनोः ७. १, १.
धेहि १. ९, ३; २. २९, २; ३६, ८; ४. ४, ४; ८; १२, ५; १४, ७^{२}; ८^{४}; १६, ७; २२, ३; ३२, ४; ५. १४, ४; २५, ३^{२}; ८; १०; ११; १२; १३; ६. १, १; २६, १; ७९, ३; ८१, २; ८२, ३; १३३, ४^{२}; १३९, ५; ७. २१, ४; ५७, २; ८१, २; ८४, १; ९४, ४; १०४, १; ८. ३, ३^{२}; २१; ९, ७; ९. ५, ५; ११. १, २१; २३; ६, ९; ७, २५; १२, ४; १२. १, १२; १६; ६३^{२}; २, ४५; ४६; १३. १, १२; १४. २, ६; १६. ९, ४; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १८. १, ४२; ४३; २, १२^{२}; ३, १; ७१; ४, ११; ४६; ४७; १९. ३, ३; ४, ३; ३१, १२; १३; ३७, २; ५२, १; २; ६४, ४; २०. ५५, ३; ७१, १३; १४; ८९, ७.
ध्राजिः ९. १५, २६.
ध्राजिम् ६. १८, १.
ध्राज्या ३. १, ५; २, ३.
ध्रियताम् ६. १७, १; २; ३; ४; १४१, १; ९. १, ११; १२; १३; १६; १७.
ध्रियस्व १२. ३, ३५.
ध्रुवः ६. ८७, १; २; ८८, १; ३; १९. ४५, ४.
ध्रुवम् ६. ८७, ३; ८८, १; २^{४}; ७. ९९, १; १०२, १^{२}; ९. १५, ८; १४. १, ४७.
ध्रुवयः १९. १०, ८.
ध्रुवा ३. १२, २; २७, ५; ६. ८८, १^{२}; १२. ३, ११; १८. ४, ५.
ध्रुवाऽइव १२. १, ४५.
ध्रुवाः २. २६, ४; ८. ७, ८; १२. १, २७; १७. १, ३०.

ध्रु॒वाम् **३.** १२, १; **१२.** १, ११; १७; **१५.** ६, १; १४, ९.

ध्रु॒वाय॑ **६.** ८८, ३.

ध्रु॒वाया॑ः **४.** ४०, ५; ६; **५.** १०, ५; **९.** ३, २९; **१५.** ४, १३; १५; ५, १०; ११; **१९.** १७, ९; १८, ९.

ध्रु॒वाया॑म् **३.** २६, ५; **४.** १४, ८; **१८.** ३, ३४.

ध्रु॒वायै॑ **१२.** ३, ५९.

ध्रु॒वास॑ः **६.** ८८, १.

ध्रु॒वे **१८.** ४, ६.

ध्रु॒वेण॑ **६.** ८७, ३; **७.** ९९, १.

ध्व॒जेषु॑ **१९.** १३, ११.

ध्व॒नय॑ः **५.** २०, ७.

ध्व॒सनौ॑ **९.** १५, ७.

ध्वाङ्क्ष॑ः **१२.** ४, ८.

ध्वाङ्क्षा॑ः **११.** ११, ९.

न

न **१.** ११, ४; २०, ४[२]; २७, ३[२]; ३२, १; २; ३४, ५; ३५, २[२]; **२.** ५, २[३]; ३[२]; १५, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; २७, १; ३०, १; ३५, १; ३; **३.** २, ६; ६, ७; ८, ४; २९, २; ३; ६[२]; ३०, ४; **४.** १, ७; ३, ७[२]; ५, २[२]; ६, ३[२]; ७, ३; ५; ६; ८, ७; ९, ५[४]; ७; ११, ३[२]; ५[४]; १४, ४; १६, ४; १८, ६; १९, २; २१, २; ३[३]; ४[२]; २२, ५; २५, २; २६, ६; ७; २८, ५; ३४, २; ३; ४; ३५, १; ४; ३६, ६; ७[३]; ८; १०; **५.** ६, ३; ११, २; ३[२]; ४[२]; १२, ५; १३, ३; १०[२]; ११[२]; १४, ९; १७, ३; ५; ९[२]; १२; १३; १४; १५; १६[२]; १७; १८[२]; १८, १; ५; ६; ७; ९; १३; १९, १; ४; १०; १५[३]; २२, ९; २९, ११; ३०, ८; ३१, ११; **६.** २, २; ८, १; २; ३; २६, २; २७, ३; ३२, १; ३३, २[२]; ४२, ३; ४३, ३; ४५, १; ४६, १[२]; ४७, २; ५०, १; ५६, १[२]; ७५, २; ३; ७६, ३; ४[२]; ९८, १; १०९, २; ११४, २; ३; ११६, १; ११८, २; १३०, ३; **७.** ८, १; १०, ३; १९, २[२]; २७, २; ३८, १; ३९, ४[२]; ४५, १; ५२, ६; ५८, ६[३]; ८; ७५, २; ८४, ४; ८५, ३; ८९, ३; १०६, १; १२२, १; **८.** १, ६; १०; २, १३; २४[३]; ३, १८; ४, ३; १३[२]; ५, १३[३]; १९; ६, १२; ८, ६; १६; ९, ९; २६; १५, २; **९.** २, २[३]; १२; १९[२]; २४[३]; ४, १८; ५, ९; २३[२]; २७; ७, ७[४]; ९; ८, ७; ९; ११, ४; १४, ७; १०; ११[२]; १५; १९; २१[२]; १५, १०; १५; १६; १८; २६; २७; **१०.** १, २६; २, ३०[२]; ४, ८[२]; ७, ८; ३१; ३७[३]; ४२[२]; ४३; ८, ८; १४; १६; ३२[४]; ४२; ४४[२]; **११.** १, ३३; २, २५[२]; ३, २४[३]; २५; ३०[२]; ४, १[३]; २[३]; ३[३]; ४[३]; ५[३]; ६[३]; ७[३]; ८[३]; ९[३]; १०[४]; ११[३]; १२[३]; १३[३]; १४[३]; १५[३]; १६[३]; १७[२]; १८[३]; ५, ६; ७; ६, १०; २१[६]; २५; २६; १०, २२; १२, २७; **१२.** १, ३७; २, १; २५; ३६; ३७; ३, ४८[३]; ४, २; १२; १३; १८; १९[२]; २७[२]; ३२; ४३; ४४; ४६; ४९; ५०; **१३.** १, १२; ५६; ५७; २, १५[२]; ४, ११; ५, ३[३]; ४[३]; ५[३]; ६; **१४.** १, ३; ५; १७; १८; २९; ३०; ३२; ३३; ५७; २, ८; **१५.** ५, २[३]; ३[२]; ५[३]; ७[३]; ९[३]; ११[३]; १३[३]; १५[३]; १६[२]; **६**, १९; १०, २[२]; १२, ३[२]; ६; ९[२]; ११; १३, १२;

१६. ६, ११; **१७.** १, ७; १२; **१८.** १, २; ४; ९^{२}; १३^{३}; १४; १५; ३३; ३६; ३९^{२}; ४८; ५०; २, ३२; ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५; ५०; ५१; ५८; ३, २२; ४१; ६३; ४, ५९; ६०; ८९; **१९.** १३, २; १४, १; ३२, २^{२}; ३४, ७^{२}; ३६, २; ३८, १^{२}; ३९, ८; ४४, ६; ४६, ३^{२}; ४७, २^{२}; ४९, ७^{२}; ८^{२}; १०^{२}; ५०, ३; ४; ५३, ४; ५६, ४^{२}; **२०.** ९, १; २; ४; १२, ४^{२}; १४, १; १५, २; ३^{२}; १६, १^{२}; २; ६; ८^{२}; ९; ११; १७, १; २; ४; ५^{४}; ७^{२}; ८; ९; १८, २; ३; २०, ६; २१, १; २३, ५; ६; २५, २; २७, ४^{२}; २८, ३; ३०, १; २; ४^{२}; ३१, ५; ३४, ५; ९; १०; ३५, १; ४; ८; १०; १२; ३६, ११^{२}; ३७, १; ३९, ४; ४४, २; ४७, ३; ४९, ४; ५; ७; ५१, ४; ५२, १; ५३, २; ३; ५७, ९; १२; १३; १४; ५८, १; २; ५९, ३^{२}; ६०, ४; ६२, १; ६४, १; ५; ६५, ३^{२}; ६७, ३; ६९, २; ७०, १३; ७१, १; ३; ४; ७२, १^{२}; ७३, २^{२}; ७६, १; ४; ५; ८; ७७, २; ३; ७८, १; २; ८१, १^{२}; ८२, १; ८५, २; ८९, २; ४; ५; ८; ९; ९२, ५; १२; १७; १८; २०^{२}; ९४, ६; ९६, ३; ४; ९७, ३; ९८, २; १००, २; १०२, २; १०५, २; ५; १०७, १५; ११२, २; ११५, ३; ११६, १; ११७, १; ११८, १; १२१, २^{४}; १२२, २; ३; १२५, २; ३; १२६, १; ५; ६^{४}; १२; १५; १६; १७; १३७, ८; १४; १४०, १; ३; १४२, ४.

नऽईव **१.** ११, ४^{२}; **१०.** ८, २५.

नः **१.** २, २; ४, २; ३; ५, १; २; ३; ६, १^{२}; ४^{३}; ७, ३; ५; ६; १०, ४; १२, १; १३, २; ४; १६, ४^{२}; १८, १; १९, १; ३; ४; २०, १^{३}; २१, १; २; २५, १; २; ३; २६, ३; ४; २९, २^{२}; ३१, २; ३; ४^{२}; ३३, १; २; ३; ४; ३४, १; **२.** १, ३; ३, ६; ४, २; ३; ६; ५, ४; ६, ३; ७, २; ३; ४^{३}; ५; १२, ४; ६; १३, २; २५, १; २७, ७^{२}; २९, ३; ४; ३५, १; २; ३६, १^{२}; **३.** १, १; २, १; ४, २; ४; १०, १; २; ३; ७; ८; १३; १२, ४; १५, १^{२}; ४^{३}; ७; १६, ३^{२}; ५; ७^{२}; १७, २; ४; ८^{२}; ९; १९, ३; २०, १; २^{४}; ३; ५^{२}; ६^{२}; ८; २६, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{२}; २८, ३; ५; ६; **४.** ७, ७; ९, ६; १०; १०, १; ३; ४; ६; ११, ५; १५, १०; १२; १७, २; २३, १; २^{२}; ३; ४; ५; ६; ७; २४, १; २; ३; ४; ५; ६; ७; २५, १; २; ३; ४; ५; ६; ७^{२}; २६, १; २; ३; ४; ५; ६; ७; २७, १; २; ३^{२}; ४; ५; ६; ७; २८, १; २; ३; ४; ५; ६; ७^{२}; २९, १; २; ३; ४; ५; ६; ७; ३१, २; ६; ३२, २; ३; ५; ६^{२}; ७; ३३, १^{२}; २; ३; ४; ५; ६; ७^{२}; ८^{२}; ३६, १^{२}; २; ३८, ३^{३}; ५; **५.** ३, २; ५; ६^{३}; ७^{२}; ८^{३}; १०^{२}; ११; ५, ५; ९; ६, २; ५; ६; ७; ७, १^{२}; ३; ६^{३}; ११, ११; १२, २; ८; १८, १४; १९, ९; २१, ८; १२; २२, ९; १०; २७, ८; ९^{२}; १०; २९, २; **६.** १, ३; ३, १^{२}; २^{३}; ३^{२}; ४, १; ३^{२}; ६, २; ३; ७, १; २^{२}; ३; २३, ३; २४, ३; २६, १; २; २७, १; २^{४}; ३^{२}; २८, १; २९, २; ३२, १; ३; ३३, ३; ३४, १; २; ३; ४; ५; ३५, १^{२}; २; ३७, २^{२}; ३^{२}; ३८,

१; २; ३; ४; ३९, २[२]; ४०, १[४]; २[२]; ३[३]; ४१, ३[४]; ४५, ३; ४६, २; ४७, १; ३; ५१, २; ३; ५३, १; २[३]; ३[२]; ५५, २[२]; ५६, १; ५७, २; ३[५]; ५९, ३; ६२, १[२]; ६३, ४; ६५, १; ७७, ३; ७९, १[२]; २; ३[२]; ९३, ३; ९६, १; ३; ९९, २; ३; १०४, २; ३; १०६, २; ३; १०७, १[२]; २[२]; ३[२]; ४[२]; १०८, १[३]; ११४, १; २; ११५, १; ११६, १; २; ३; ११८, १; २[२]; ११९, १; १२०, १; २[३]; १२१, २; १२३, ५; १२५, ३; १२६, २; ३; १२८, २[४]; ४; १३१, ३; १३३, १[२]; ४[२]; **७.** २, १; ५, ५; ७, २; १०, ४; १२, १; १८, १[२]; ४; १९, १; २१, १; २[२]; ४[२]; ६; २३, १; २५, १; २७, ३; २९, १; ३२, १[२]; ४०, १; ४२, २; ४३, १; २; ४५, १; ४८, १; ४९, १; २[२]; ५०, १; २; ५१, १[३]; ५२, ३; ५३, १[२]; ५४, १; ५५, ६; ५७, २; ६१, १[२]; ६२, २; ३; ५; ६५, १; ७०, १; ७१, १; ७२, १[४]; ७३, ३; ७७, ७; ९; ८२, २; ८४, १[२]; ३; ४; ८५, २; ३; ८७, १; ८८, २[२]; ८९, १; ९१, १; ९६, १; ९९, १; १०२, २; ८; १११, १[२]; ११३, १[३]; २; ११४, १; ५[२]; ७; ११५, ३; ११७, १; १२०, २; **८.** २, १७; ३, १; १९; २०; ४, १०; २३[२]; ५, १७[३]; ७, १७; ९, ७; १७; **९.** ३, ६; २४; ४, २; २२[२]; २३; २४[२]; ५, २; १७; १९; १५, ४; १२[२]; **१०.** १, ६; २०; २२; २९; ३, ८; ५, २३; ४५; ६, ४; ५; **११.** १, १७; २, १; ८[३]; ११; १९[२]; २०[३]; २१[२]; २६[२]; २९[६]; ३१[२]; ६, ५; ६[२]; ९; ८, १; २; ३; ४; ५; ६; ८;

९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; ११, २; २३; १२, २६; **१२.** १, १[२]; २[२]; ३; ४; ५; ६; ७; ८; ९; १०; १२[३]; १३; १४[२]; १६; १८[२]; २२; २३; २४; २५; ३०[२]; ३२[२]; ३४; ३६; ४०; ४१; ४३; ४४; ४६[२]; ४७; ५२; ६२; २, ३[२]; ७; १३; १५[२]; १८; २२; २३; ४९; ३, १०; ११; १२[३]; १५; १६; १७[२]; २६; ३१; ४५; ४६; ४८; ५५[३]; ५६[२]; ५७[३]; ५८[३]; ५९[३]; ६०[३]; ४, ४९; **१३.** १, १७[३]; १८; १९[२]; २९; ५९; २, ३७; **१४.** १, ३४; ६०; २, १; ३८; ४०; ४५; ५१; ६७; **१६.** ५, ३; ४; ५; ६; ७; १०; ६, ४; **१७.** १, ६; ७; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४; १५; १६; १७; १८; १९; २४; **१८.** १, १९[३]; २५[२]; २६; ३०; ३१; ३३; ३६; ३९[२]; ४४; ४७; ५०[२]; ५१; ५२[२]; ५८; २, ३; २९; ४९; ३, १४; १५; १६[२]; २१; २२; ३९; ४४; ४५; ४६; ५९[२]; ६१; ६२[२]; ६३; ६७[२]; ४, ४०; ४८; ५०; ५३; ५४; ६२; ६३; **१९.** ३, १; २; ४; ४, २; ३[४]; ८, ७[२]; ९, १; २[२]; ३; ४; ५; ६[२]; ७[२]; ८; ९[४]; १०[२]; ११; १४; १०, १[३]; २[५]; ३[५]; ४[४]; ५[४]; ६[३]; ७[५]; ८[४]; ९[५]; १०[४]; ११, १[४]; २[३]; ३[३]; ४; ५[२]; १४, १; १५, १[२]; २; ३; ४; ५[२]; ६; १६, १; २४, ४; २७, १४; ३१, २; ३; १३; १४[२]; ३२, ६; ९; १०; ३३, १[२]; ३४, ४; ५; ३५, २; ४०, २; ३[४]; ४; ४४, ४; ८; ९; ४५, २; ४७, ५; ६[२]; ९; ४८, २[२]; ३; ४; ५[२]; ६; ४९, ५; ६; ५०, २; ७[२]; ५२, ५; ५५, २; ३; ४;

५६, ६; ५७, ४; ५८, १; **२०.** ३, २; ४, १; ६, ३; ६; ८[२]; ७, ३; ८, २; १२, ४; ६[२]; १३, ३; १४, २; ३; ४; १५, ४; १६, १२; १७, ११[२]; १२; १८, ४; ५; २०, १; ४; ६[३]; २३, १; २; ४; २४, १; ७; २६, २; ३६, २; ४; ७; १०; ११; ३७, ७; ११[२]; ३८, २; ४५, १; ३; ४६, २; ३[२]; ४७, ८; ५५, १; ५६, १; ४; ५; ६; ५७, २; ३; ४; ७; ९[३]; ६२, २; ३; ४; ६३, १; ५; ६४, १; ६८, २; ३; ५; ६; ६९, १[२]; ६; ८; ७०, १०; १२; ७२, ३; ७४, १; २; ३; ४; ५; ६; ७; ७६, ४; ७७, १; २; ८; ७८, ३; ७९, १[२]; २; ८०, १; २; ८२, २; ८३, २; ८४, ३; ८७, ७; ८८, २; ८९, ३; ११[२]; ९०, १; ९१, १; १२; ९४, ११[२]; ९५, ४[२]; ९७, २; ९८, २; १०१, ३; १०४, ३; १०८, १; २; ३; ११०, १; ३; ११३, १; १२२, १; १२४, १; ३; ४; १२५, ६; १२६, ८; १३७, ३[२]; १४१, १[२]; १४३, ५; ६; ८[२].

नकिः **२.** ३१, ३; **१८.** १, ५; **२०.** ५३, २; ५७, १२; ६४, ५; ९२, १८; ११४, २; ११८, २.

नकुलः **६.** १३९, ५; **८.** ७, २३.

नक्तऽभिः **८.** ४, १८.

नक्तम् **५.** ७, ३; २९, ९; ३०, १०; **६.** २३, १; १२८, ४; **८.** ३, १; ४, ११; १७; ५, २२; **१६.** ७, १०; **१९.** १५, ६.

नक्तम्ऽजाता **१.** २३, १.

नक्षति **५.** २७, ३.

नक्षतु **७.** ७७, ५.

नक्षते **२०.** ३६, ५.

नक्षत्ऽदाभम् **२०.** ३६, २.

नक्षत्रऽजाः **६.** ११०, ३.

नक्षत्रम् **१०.** २, २२; २३; **१९.** ९, ९.

नक्षत्रऽराज **६.** १२८, ४.

नक्षत्रा **१३.** २, १७; ६, ७; **२०.** ४७, १४.

नक्षत्राणाम् **३.** ७, ७; **५.** २४, १०; **६.** ८६, २; **७.** १४, १; **१४.** १, २; **१५.** ६, ६.

नक्षत्राणि **६.** १२८, १; **९.** १२, १५; **११.** ८, १०; **१५.** ६, ५; १७, ४; **१९.** ८, १.

नक्षत्रिये **२.** २, ४.

नक्षत्रेभिः **२०.** १६, ११.

नक्षत्रेभ्यः **६.** १०, ३; १२८, ३.

नक्षत्रैः **१९.** १९, ४; २७, २.

नक्षन् **२०.** १२, ४.

नक्षमाणः **२०.** १६, २.

नक्षमाणाः **१८.** २, २९.

नक्षमाणौ **१२.** ३, ८.

नक्षस्व **१०.** १, १४.

नखान् **४.** ३, ३.

नखेभ्यः **२.** ३३, ६; **२०.** ९६, २२.

नगेषु **१९.** ८, १.

नग्नकात् **८.** ६, २१.

नग्ना **५.** ७, ८.

नघऽरिषाम् **८.** २, ६; ७, ६.

नट् **८.** ४, २३.

नडम् **६.** १३८, ५; **१२.** २, १; ५०; ५४.

नडम्ऽइव **४.** १९, १.

नडाःऽइव **६.** १३७, २; ३.

नडे **१२.** २, १९.

नदतः **४.** १५, १; ५.

नदनिमा **५.** २३, ८.

नदनुम् **२०.** ११४, २.

नदस्य **१८.** १, १९.

नदी **१**. ८, १; **९**. १२, १४; **१२**. २, २७.
नदीःऽइव **३**. २४, ३.
नदीनाम् **१**. १५, ३; **६**. ५२, २; ११३, २; **१४**. १, ४३; **१८**. ३, ५.
नदीभिः **१९**. १९, ६.
नदीम् **४**. ३७, ३.
नदीषु **४**. ३६, ५.
नद्यम् **९**. ३, २.
नद्या **९**. ३, १०.
नद्यानि **९**. ३, १; ४; ५.
नद्यं **१९**. ३९, २; ३; ४.
नद्यः **३**. १३, १; **६**. १२, ३; २४, ३; **७**. ३९, ५; **११**. ८, १०; **१४**. २, ७; **१९**. १, १; **२०**. १३७, ८.
नद्यम् **२०**. ५७, ३.
नद्यऽमारः **१९**. ३९, २.
नद्यऽरिषः **१९**. ३९, २.
ननान्दुः **१४**. १, ४४.
ननाश **१८**. १, ५२.
ननु **२**. १, ४; **४**. ३१, ३; **११**. ६, २५; **१३**. २, १३; **१९**. ३२, ९.
नन्दन्ति **९**. १, १; **१९**. ५३, ७.
नन्दान् **१०**. २, ९.
नपात् **१९**. ११, ३.
नपात् **१**. १३, २; ३; २६, ३; **६**. ३, १; ३; **१४**. १, ३७; **२०**. ५, ७.
नपातम् **१८**. १, १; ४५; **१९**. ४२, ४; **२०**. १०३, ३.
नपाता **२०**. १४३, २.
नप्तिः **९**. १, ३; १०.
नप्तृऽभिः **१४**. १, २२.
नप्त्यः **२**. १४, १; **७**. ८७, ६; **१३**. २, २४; **२०**. ४७, २१.
नप्त्यम् **१**. २८, ४.
नभः **४**. १५, ५; **७**. १९, १; **१३**. ४, २; ३[२]; ४; ५; ६; ७; ९; ५, १; ६, १; **२०**. १३७, ८; १४०, ३.
नभःऽभिः **६**. ६२, १.
नभताम् **७**. १९, २.
नभन्ताम् **२०**. ९५, २; ३; ४.
नभसः **६**. ७९, १; **१८**. ४, १४.
नभसः ९. ४, २२.
नभसः **६**. ७९, २.
नभसा **५**. १३, ३.
नभसी इति **५**. १८, ५; २०, ७; **११**. ७ ८; ११; **१२**. ३, ५; ६; **१७**. १, १६.
नभस्व **७**. १९, १.
नभस्वतः **४**. १५, १; ५.
नभस्वतीः **४**. १५, १.
नभांसि **४**. १५, ३.
नभ्यम् **६**. ७०, ३; **१२**. १, १२.
नभ्यानि **१०**. ८, ४.
नम **१**. २, २.
नमः **१**. १०, २; १३, १[३]; २; ३[२]; ४; २५, ४[३]; ३२, ४; **२**. २, १; ४; ५; ८, ४[२]; ५[३]; ३५, ४[३]; **३**. २६, १; २; ३; ४; ५; ६; २७, १[४]; २[४]; ३[४]; ४[४]; ५[४]; ६[४]; **५**. १, ५; ५, १; ७, १[२]; २; ३; ९; १०; २२, ४; २८, ११; ३०, १२[३]; **६**. १३, १[३]; २[४]; ३[४]; २०, १; २[६]; ३; २८, ३; ५५, ३; ५६, १; २[४]; ६३, २[२]; ८४, ३; ९०, ३[४]; ९३, २; १२८, ४; १३१, २; **७**. ३३, १; ९२, १; ११४, १; १२१, १[२]; **८**. १, १; १४; २, ४[२]; **९**. २, १९; २०; २१; २२; २३; २४; ३, १२[४]; १३; २५; २६; २७; २८; २९; ३०; ३१;

१०. ७, ३२; ३३; ३४; ३६; ८, १; १०, १[३]; ११. २, १; ३; ४[२]; ५; ६; ८; ९[२]; ११; १२; १४; १५[४]; १६[५]; १८; १९; २२; २३; २७; ३०; ३१[५]; ६, १; २[४]; ७[४]; ८[५]; २३; १२. १, २६; ४२; ३, ११; ४, ४५; १३. ८, ३; ५; ६; ९, १; २; ४; १४. २, २०; ३४; ३५[३]; ४६; ४८; १५. १८, ५; १६. २, ६; १७. १, २२[६]; २३[६]; १८. १, ४६; २, २; ४, ७१; ७२; ७३; ७४; ८१[२]; ८२[२]; ८३[२]; ८४[२]; ८५; १९. ८, २; ७; ११, ६; ५५, ५; २०. १६, १२; १४३, ३.

नमः ७. ५८, ४.

नमःऽकारेण ४. ३९, ९.

नमःऽकृताभ्यः ११. २, ३१.

नमःऽकृत्य ७. १०७, १.

नमःऽभिः ३. ८, ३; ७. ५२, ३; १८. ३, १६; ३९.

नमःऽवाके १३. ६, ५.

नमःऽवृक्तिम् २०. १२५, २.

नमन्त ३. १६, ६; २०. १०७, १.

नमन्ताम् ५. ३, १; ९. २, ११; २०. ८९, ६.

नमन्ति २०. ५४, ३.

नमन्तु ४. ३, १; ३९, १; ३; ५; ७; ५. ८, २.

नमयामसि ३. ८, ५; ६. ९४, १.

नमसा ३. ३, १; १५, ७; ४. १, ७; ३९, ९; ५. २७, ४; ७. ८, १; १०. ४, २३; १४. २, ३३; १८. २, ४९; २०. १५, ३; ८८, ६; १०९, ३.

नमसानाः ६. ३९, २.

नमसे १४. २, ३९.

नमस्यः २. २, १; २; ३. ४, १; ६. ९८, १; २०. १०२, १.

नमस्यन्तः १. १२, २.

नमस्ये३इति ४. २६, ३.

नमस्येभ्यः ६. ९३, २.

नमस्वन्तः ९. १४, ८.

नमस्विनः २०. ९२, १४.

नमांसि १. २५, १.

नमामसि ३. ८, ५; ६. ९४, १.

नमुचिम् २०. २१, ७; ३७, ५.

नमुचेः २०. २९, ३.

नमुचौ २०. १२५, ४.

नमुरात् १३. ८, १.

नमेते इति २०. ३४, १४.

नम्या २०. २१, ७.

नय २. ९, १; २८, ५; ३. ३, १; ५. १४, ४; ६. ५, १; २; ८. ३, ९; ९. ५, १; १०. १, २६.

नयत ८. ८, ११.

नयत ७. ८७, १.

नयति ४. २४, ७; ५. १८, ४.

नयति ९. ६, ४.

नयतु २. २६, २[२]; ३६, ८[२]; ३. ३, ४; ६. ५९, ३; १२. २, २४; १४. १, २०; १९. ४३, १; २; ३; ४; ५; ६; ७; ८.

नयते ५. १९, १५.

नयथ ४. १३, १.

नयन्ति ५. ३०, १२; ८. १, ८.

नयन्ति १३. १, २३; १४. १, ४६; २०. २५, २.

नयन्ती ६. ९२, ३.

नयन्तु १४. २, १०.

नयन्तु ६. ४७, ३; ९३, २; १२. ३, २६; १९. ४६, ४.

नयस्व १. ८, ३.

नयाति ३. ११, ३; २०. ९६, ८.
नयाति ६. ११९, १; १२०, १; १२१, २.
नयाथः २. ३०, २.
नयाम् १९. २४, २; ३.
नयामः ६. २८, १; १०. १, १९.
नयामसि १. १८, १; ५. ७, ७; १४, ६; ७; २९, ८; ६. ४३, ३; ४६, ३; ७. ९९, १; १९. ५७, १.
नयामि १०. ४, २१.
नयामि १. १०, १; ३. १९, ३; ८. ८, १०; ९. ५, २; १९. १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११.
नयासि १२. ३, १७.
नयासै ४. ३१, ३.
नरः ३. १७, ६; ४. ३१, १; ६. १२६, ३; ९. १, ३; १४. १, ४६; १९. ५६, ४; २०. २९, ४; ३७, ८; ९; ५२, २; ५७, १५; ७१, २; ७६, ५; ९८, १; १०३, १; १०७, १९; १४३, ६.
नरः ३. १९, ७; ६. २२, २; १४. २, ९; १४; १९. १३, ३; २०. ६७, ४; १३७, २.
नरकम् १२. ४, ३६.
नरम् २०. २६, ३; ४४, १; ५४, १; ६५, १.
नराच्याम् ५. ३१, ४.
नराम् २०. ३७, १०.
नराशंसः ५. २७, ३.
नरिष्टा ७. १३, २; ११. १०, २४.
नर्यऽअपसम् २०. ७, १.
नर्यः २०. ७६, १; ७.
नर्या २०. ११, ५.
नर्याणि १९. ४९, ३; २०. ७७, ६.
नलदस्य ६. १०२, ३.
नलदी ४. ३७, ३.
नव ५. १५, ९; १९, ११; २८, १; ६. २५, ३; ११. ९, १४; १३. ४, १०; १९. ४७, ३; ५७, ५; २०. ७, २; २१, ९; ३७, ५; ४१, १.
नवऽऋचेभ्यः १९. २३, ६.
नवः ७. ८६, १; १४. १, २३.
नवःऽनवः ७. ८६, २; १४. १, २४.
नवऽगत् ३. १०, ४; ८. ९, ११.
नवऽग्वाः १८. १, ५८; ३, २०; २०. ३६, २.
नवऽग्वैः १४. १, ५६.
नवतयः ५. १९, ११.
नवतिः ५. १५, ९; ६. २५, ३; १९. ४७, ३.
नवतिम् ८. ५, ९; १०. १, १६; २०. ७, २; २१, ९; ३७, ५.
नवतीः २०. ४१, १.
नवऽद्वारम् १०. ८, ४३.
नवऽद्वारा १०. २, ३१.
नवऽधा १३. ४, १०.
नवन्त ५. २, २; ९. १४, ३; २०. १०७, ५.
नवऽपदी ९. १५, २१; १३. १, ४२.
नवऽभिः ५. २८, १.
नवम् १२. ३, ३२; १४. २, ४४; २०. ६६, २; ९२, १२; १२६, १८.
नवमः १३. ५, ५.
नवऽवृषः ५. १६, ९.
नवऽस्रक्तिम् २०. ४२, १.
नवाः १२. २, ४१; १९. ३४, ७.
नवानि ९. ५, २९.
नवामहे २०. ९, १; ४९, ४.
नवायाम् २०. ९६, ५.
नविष्टौ २०. १८, २.

नवीयः ७. ७६, १; १८. २, ३१; ३, १७; १९. ११, ४.
नवीयसः २०. ७२, ३[२].
नव्यः ६. ११०, १; २०. ३५, १३; ५०, १.
नव्यः २. ५, २.
नव्यम् २०. ४४, १; ६७, २.
नव्यम्ऽनव्यम् २०. ३२, १.
नव्यस्या २०. ३६, ७.
नशत् ९. १४, २१; २०. २०, ६; ५७, ९; ९२, १८.
नशन्त २०. ९५, ४.
नशन्ति ४. २१, ३.
नशिष्यति ६. ८३, ३.
नश्यं ७. १२०, १.
नश्य ६. ११३, २.
नश्यत २. १४, ५; ६.
नश्यन्ति ४. ३६, ७; ८.
नश्यन्तु ६. २५, १; २; ३.
नष्टऽअसवः १०. ४, १२.
नष्टम् ७. १०, ४.
नष्टऽविषाः १०. ४, १२.
नष्टेन ७. १०, ४.
नसा २. २७, २; ५. १४, १.
नसोः १९. ६०, १.
नस्वती १०. १, २.
नहना २०. ९१, ३.
नहनानाम् ९. ३, ४.
नहि ३. १८, ३; ६. ४९, १; ७. १०६, १; ९. १४, १३; १७; १२. १, ४१; २०. १२, २; १५, ४; ५०, १; ८२, २; ९३, २; १२५, ३; १२६, ११.
नह्य ६. ६७, ३; १०. ९, १.
नह्यत ५. ८, ४; ७. ५२, ९.
नह्यतम् ६. ५०, १.
नह्यध्वम् ११. ११, २; २६; १२, १.
नह्यस्व १४. १, ४२.
नह्यामि १. १४, ४; ७. ७३, ४; ५[२]; १००, ३; १४. २, ७०[३].
नाकः १०. १०, ११; १३. १, ७.
नाकऽपालः १०. ८, १२.
नाकम् १. ९, २; ४; ३. २९, ३; ४. १४, २; ६; ९; ६. ६३, ३; ८४, ४; ७. ५, १; ५५, ७; ७७, ६; ९. ५, १; ३; ६; ११. १, ४; ३०; ३७; १३. २, ४६; १९. ७, १.
नाकस्य ४. १४, ३; ७. ८५, १; ९. ५, १०; १५; ११. १, ७; १८. २, ४७; ४, ४; १४.
नाकान् १९. २७, ४.
नाके ५. ६, ३; ६. १२२, ४; १२३, ५; ७. ८५, ४; ९. ५, ४; ८; १०. ७, ४३; ११. १, ३६; १३. १, ११; १८. ३, ६६; ४, ३.
नाडीकाः ५. १८, ८.
नाड्यः १०. ७, १५; १६.
नाड्यौ ६. १३८, ४.
नाथऽकामः १३. २, ३७.
नाथम् ४. २०, ९; ९. २, ७; १८. १, १३.
नाथऽवित् ११. १, १५.
नाथितः ४. २३, ७; २४, ७; २६, ७; २७, ७; २८, ७; २९, ७; ७. ११४, ७; १३. १, १२.
नाथिता ५. २०, ५; ११. १, १.
नाथिताः ३. १, २.
नादम् १९. ३४, ३.
नादे १८. १, १९.

नाधमानस्य १३. २, ४४; २०. ३४, ६.
नाधमानाः १३. २, ४३; १७. १, १४.
नानदतम् २०. ९१, ९.
नानदती १०. १, १४.
नाना २०. २४, ८; ८९, ३; ९१, १०.
नानाऽधर्माणम् १२. १, ४५.
नानानम् १२. २, ४३.
नानाऽरथम् २०. १३, ४.
नानाऽरूपाः १४. २, २५.
नानारूपे इति नानाऽरूपे १३. २, ३.
नानाऽवीर्याः १२. १, २.
नाभयः १२. ३, ४१.
नाभा ७. ६४, १.
नाभिः १. १३, ३; ६. ९, ३; ४४, ३; १२५, ३; ९. १, ४; १५, १२; १४; १६. ४, १[२]; १८. १, ४; २०. १४३, ९.
नाभिम् ४. ११, ६; ५. २७, १०; ९. १५, १३; १२. ३, ४०; १३. १, १४; ३७.
नाभिम्ऽइव ३. ३०, ६; ११. ९, ४.
नाभीः १९. ५३, २.
नाभौ १८. ३, ४०.
नाभौऽइव १०. ८, ३४.
नाभ्याः २. ३३, ४; ९. १३, १२; १९. ६, ८; २०. ९६, २०.
नाम १. २४, ३[२]; २५, २; ३; २. ८, १; ३. ७, ४; १३, १; ३; १४, १; १८, ३; २४, २; २६, १; २; ३; ४; ५; ६; ४. ८, ३; ९, ८; १९, ५; ३१, ५; ५. १, ३; ४, ९[२]; ५, १; ३; ६; ८; ६, ४; ९, ७; २८, १२; ६. १६, २[२]; ४४, ३; ४६, १; ७६, ४; ८२, १; ८३, २; १२१, ३; ७. १, १; ७, २; १३, २[२]; २१, ४; ३०, १; ४६, १; ८६, ३; ८. २, २८; ९. ५, ३१[२]; ३२[२]; ३३[२]; ३४[२]; ३५[२]; ३६[२]; १४, ३; १०. १, ११; २, १२; ४, २४[२]; ७, २५; ३१; ८, ६; ३१; ११. ८, ४; ९, १; १०, १३; १९; ११, ४; १२. १, ५४; ४, ५; ६, ३; १५. १५, ३; ४; ५; ६; ७; ८; ९; १६. ३, ५; १७. १, १; २; ३; ४; ५; १८. १, ३४; १९. ३५, १; ३८, २; ३९, ३[२]; ४८, ६[२]; ४९, ७; ५३, ७; २०. १५, ३; १६, ७; २१, ७; ४०, ३; ४१, ३; ६७, ७; ६९, १२; १२६, २३.
नामऽग्राहात् १०. १, १२.
नामऽस्था ११. १०, ७.
नामऽधः २. १, ३.
नामऽधेयम् ७. ११४, ६.
नामऽबिभ्रती १५. १३, ११.
नामानि ३. १३, १; ५. ४, ८; १९. ३९, २; २०. १९, ३.
नाम्ना १०. ७, ३१.
नाम्नी इति ४. ९, १०.
नारद ५. १९, ९; १२. ४, १६; ४३; ४५.
नारदः १२. ४, २४.
नारदः १२. ४, ४१; ४२.
नाराशंसी १४. १, ७.
नाराशंसीः १५. ६, ११.
नाराशंसीनाम् १५. ६, १२.
नारि ३. १२, ८; २३, ५; ११. १, १३; १४; २३; १४. २, २०; ३२; १८. ३, २.
नारिषु २०. १२६, ११.
नारी १. ११, १; २. ३६, ३; ४; ५. २०, ५; १४. २, १३; १४; ६३; १८. ३, १; २०. १२६, १०.
नारीः ४. ५, ३; १२. २, ३१; १८. ३, ५७.
नारीम् १४. १, ५३; ५४; ५५; ५९.

नार्याः ५. २५, १०; ११; १२; १३.
नार्यै १४. २, २१.
नार्षदेन ४. १९, २.
नावः ५. ४, ५.
नावम् २. ३६, ५; ५. १९, ८; ७. ७, १; ९. २, ६; १२. २, ४८; १७. १, २५; २६; २०. ७२, १; ९४, ६.
नावा ४. ३३, ८; २०. ४६, २.
नावाऽइव ४. ३३, ७.
नाव्याः ८. ५, ९; ७, १५; १०. १, १६.
नाशय ५. ४, ९.
नाशय १. २३, २; ३; २. २५, ३; ३. १, ५; २, ३; ४. ३७, २; ५. २२, १३; ६. १४, १; ८. ६, ९; १०; १३; १५; १९. १५, २; ३५, ३; ३९, १; ५; ६; ७; ८.
नाशयत् १९. ४४, ७.
नाशयतु ११. १२, १६.
नाशयन् ५. ४, १.
नाशयन्तु ६. ११३, १; ३.
नाशयामः २. १४, १.
नाशयामसि ३. २३, १.
नाशयामसि १. १८, ४; ३. ७, ३; ४. १७, ५; ३७, ११; ७. २४, १; ८. ६, ११; १२; १४; २३; २०. ९६, १३; १४; १५; १६.
नाशयामि ३. ७, ६.
नाष्ट्राः ८. २, २७.
नासत्या २०. १४०, १; ४; १४१, ५; १४३, ४; ७.
नासिकाभ्याम् २. ३३, १; २०. ९६, १७.
नासिकाम् १९. ८, ५.
नासिके इति १०. २, ६; ९, १४; १५. १८, ४.
नासे इति ५. २३, ३.
नाहुषाणि २०. ३६, १०.
नि १. १, २; ३; १४, २; २२, ४; २. १२, २; १४, ३; २६, १; २; ३१, ३; ३. ११, ७; १२, १; ४[२]; १५, ५; १७, ४; २०, ८; २३, १; ४. ५, १; ७; १६, ५; २१, २; २५, ३; ६; २८, ६; ३१, ७; ३४, ८; ३८, ७; ५. २, १; ६; ३, ४; ६, ३; ९, ७; १२, ६; १३, १[२]; ५; १८, ७; २०, ८; २१, १; २३, ८; २९, ४[३]; ६. ८, २; २६, ३; २९, १; ४९, ३; ५२, २[४]; ३; ७०, १; २; ३; ७६, ३; ७७, ३; १०९, ३; १११, २; ११७, २; १३१, १[३]; १३९, २; ४; ७. ७, २; २५, १; २७, ४; ३९, २; ४२, २; ४९, १; ५४, १; ८७, ३; ९५, ३; १२०, ३; ८. १, २१; ३, ७; ११; २१; ४, १[३]; ५; १०; ५, २१; ६, २४; ८, ६; ९, १७; १०, २; ४; ६; ८; १०; १२; ९. ४, ६; १५, ७; १६[२]; २३; १०. १, १७; २७; २, २; १७; ३, १५; १७; १८; १९; २०; २१; २२; २३; २४; २५; ५, ३६; ८, ३; ७; ११. १, ३; ६; ९; ११; २८; ३३; ६, २२; २५; १०, ३३; १२, १३; १२. १, २९; ३०; ३१; ६३; २, ९; ३, ८; १४; ५५; ५६; ५७; ५८; ५९; ६०; ४, २०; २१; ११, १२; १४. २, ५; ३२; ६५; ६९; १६. ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; १७. १, १४; १८. १, ३; ९; १९; ४०; २, २०; ३, १; ११[२]; १२; ५०; ४, ४०; १९. ३१, ५;

६; ८; १३; १४; ३२, ४; ४७, २; ४९, ५; ५४, १; २०. ५, ७; १३, १; १७, २; २१, १; ६; ९; ३०, ३; ३७, २; ४; ८[२]; ५३, २; ५६, १; ५७, १२; ६३, ७; ६७, ५; ६८, ११; ७०, १८[३]; ७४, ३; ७८, २; ८८, ३; ८९, १; ५; ६; ८[२]; ९३, २; ९४, ६; ९६, १; १०७, ४; ९; ११३, २; १४३, ५.

निऽअक्ताम् १४. २, ३३.

निऽअञ्चनम् ४. ३६, ६.

निऽअञ्चनी ५. ५, २.

निऽअञ्जन्ति ९. १, १७.

निऽअयनम् ६. ७७, २; १०६, २.

निऽअर्पिताः १०. ३, १५.

निऽअर्बुदम् ८. ८, ७; १०. ८, २४; १३. ७, १७.

निऽअर्बुदिः ११. ११, ४.

निऽअर्बुदे ११. ११, ६; ११; १२; १९; १२, २०; २१.

निऽअस्तिका ६. १३९, १.

निऽअस्यथ १४. २, २२.

निऽअह्वे १८. ४, ६५.

निऽआगन् ७. ७७, ८.

निऽआनयत् ७. ३९, ५.

निऽईतः ३. ११, २; २०. ९६, ७.

निऽइत्यं १२. २, ३८.

निऽऋष्टम् २०. ८९, २.

निऽओकसे २०. ७१, १६.

निऽओचनी १४. १, ७.

निऽओचरः ५. २२, ५.

निः १. ८, ३; १८, १[२]; २[३]; २३, २; ३; २. ९, ५; १०, ८; १४, २[४]; ४; ३. २, ४; ५; ६, २; ३; ४. ६, २; ४; ५[२]; २२, १; २; ५. ४, ६; १०; ५, ४; ५; १८, ४; १९, ४; ३०, ८; १६; ६. १४, २; ३; १६, ३; १८, १; ३; २४, २; ७५, १; ९०, २; १२१, १; ७. ५८, ३; ८०, ३; ८८, ४; ११३, २; १२०, ३; ८. ८, ३; ९. २, ४; ५, २३; ३१; ३२; ३३; ३४; ३५; ३६; १३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११[२]; १२; १३; १४; १५; १६; १७; १८; १९; २०; १०. १, २१; ४, २६[२]; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ११. १, ९; ५, ३; १२. २, २; ३[२]; १२; १५; १६; ४२; ४७; ४८; ४, ५३; ११, ९; १६. २, १; ७, ६[३]; ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१; १८. २, २७; ४२; ४, ५६; १९. ४४, २; ५०, १; ५७, २; ५; २०. १६, ३; ८; ९; ६८, ५; ९१, ५; ९६, ४; १२.

निःऽअकुर्वत ४. १९, ४.

निःऽअतक्षत ९. १५, १.

निःऽअतक्षतम् १. ३२, ३.

निःऽअभनः ३. ६, ३.

निःऽआदधत् १२. २, ३९.

निःऽआदधौ १२. २, ५४.

निःऽआवहन् ५. ४, ५.

निःऽईन्द्रियाः ९. २, १०.

निःऽउप्यन्ते ९. ६, १४.

निःऽऊहन् ८. २, ९.

निःऽकृतिः २. १०, ५; ३. ६, ५; ४. ३६, १०; ६. ६३, १; ८४, १; १२४, ३; ७. ७३, १; २; ९. १५, १०; १०. २, १०;

११. १०, १९; १२. ३, १७; ८, १०; १८. १, १२.
निःऽऋतिम् ६. ९७, २; १२४, २; ७. ४३, १; ८. १, २१; २, १२; ९. ५, १८; १२ २, ३.
निःऽऋतीनाम् २०. ६६, ३.
निःऽऋते १९. ४४, ४.
निःऽऋते ६. २९, २; ६३, २; ८४, ३; ७. ६६, २; १४. २, १९.
निःऽऋतेः ३. ११, २; ७. ५५, ३; ८. ४, ९; ११. १, २९; २०. ९६, ७.
निःऽऋत्यै १०. २, २.
निःऽऋत्याः १. ३१, २; २. १०, १; २; ३; ४; ५; ६; ७; ८; ६. २७, १; ८. १, ३; १०. ३, ७; १६. ५, ४; ८, ५; १८. ३, २६; १९. ४४, ४.
निःऽऋत्यै २. २५, १; ५. ७, ९; २०. ९६, २४.
निःऽऋथः ६. ९३, १; १२. २, १४.
निःऽऋथम् ८. ४, १४.
निःऽऋथात् ५. ३, ९.
निःऽऐतु १०. ४, २१; २२.
निःऽकर्ता १४. २, ४७.
निःऽक्रृतिः ५. ५, ४; ६.
निःऽक्रृतिम् ६. २७, १; ४९, ३; १८. ४, ६०.
निःऽकृते ५. ५, ६.
निःऽक्रृतेः ४. २७, ६.
निःऽक्रीतः २. ३४, १.
निःऽखिदन् ५. १८, ७.
निःऽजरायवः १. २७, १.
निःऽतक्करीम् ५. २२, ६.
निःऽततक्षतुः २०. ११३, २.
निःऽदहनी १४. २, ४८.
निःऽदाहः १६. १, ३.
निःऽदाहम् ५. ३१, ९.
निःऽधर्यन्ति ९. १३, १८.
निःऽनयते ११. २, २२.
निःऽभक्तम् २. ३५, २.
निःऽभूत्या १६. ७, १.
निःऽभूत्याः १६. ५, ६; ८, ७.
निःऽमथ्यते १०. ८, २०.
निःऽमितः ४. ३५, ४.
निःऽमितम् ८. ९, ४.
निःऽमिता ८. ९, ४; ५.
निःऽमिमीते १३. ३, ८.
निःऽमुक्त्यै १२. ३, ५.
निःऽयाचन् ६. १३३, ३.
निःऽशसा ६. ४५, २.
निःऽसालाम् २. १४, १.
निःऽसृजः २०. ७२, २[२]; ७५, १[२].
निःऽसृप्यं ११. १, २५.
निःऽहतम् १९. ९, ८.
निःऽहस्तः ६. ६६, १.
निःऽहस्ताः ६. ६६, २; ३.
निःऽहस्तान् ३. १, १; २, १.
निःऽहस्तेभ्यः ६. ६५, २.
निऽकर्तुम् १०. १, २६.
निऽकामः २०. ३०, ३.
निऽकामः १५. ११, २; १०; ११.
निऽकामम् १५. ११, १०.
निऽकामस्य १५. ११, ११.
निऽकामे १५. ११, ११.
निऽकामैः २०. ७७, ६.
निऽकारिणः ७. ८७, ३.
निऽकिल्बिषम् ५. १७, ११.

निऽक्रमणम् १. ३४, ३.
निक्षं १९. २९, १[४].
निक्ष्व ८. ३, २९.
निऽखनन्तः ६. ११६, १.
निऽखातम् १०. १, १९.
निऽखाताः १८. २, ३४; १९. ९, ९.
निऽगच्छात् १८. १, १२; १४.
निऽगतम् १३. ४, १२; ५, ७.
निऽघ्नतः १०. १, २७.
निऽघ्नन्तः १९. ४६, ३.
निऽचक्रे ७. ३९, २.
निऽचख्नुः ५. ३१, ८; १०. १, १८.
निऽचिकीर्षति ११. २, १३.
निऽचिकेषि १. १०, २.
निऽचिक्यत् ५. २०, १२.
निऽचितः २०. ३४, १४.
निऽजः ३. ५, २.
निऽजूर्वति ६. ३४, २.
निऽजूर्वथः ८. ४, ४.
निऽजूर्वन् ६. ५२, १.
निण्यः ९. १५, १५.
निण्यम् २०. ७७, ३.
निऽतत्नि ६. १३६, १.
निऽतपन् १९. २८, ३.
निऽतानाः ६. १३९, १.
निऽतुदन्तीम् ५. ७, ७.
निऽतोदिनः ७. ९५, ३.
निऽतोदिनौ ७. १००, ३.
नित्यः १८. १, ३०.
नित्यऽवत्साम् ७. १०९, १; ९. ४, २१.
निदः २०. ६८, ५.
निऽदधत् १८. ३, ५२.
निऽदधुः ३. ५, ३.

निऽदधे ९. ५, १९.
निदे २०. १८, ५; २३, ६.
निऽधनम् ९. १०, २; ३; ५[२]; ७[२]; ९; १०; १२, १८; ११. ९, १२; १२. १, ४८; ५, ३.
निऽधिः १२. ४, २९.
निधिऽपतिः ७. १८, ४.
निधिऽपाः १२. ३, ३४; ४१; ४२.
निधिऽभिः ७. ७५, २.
निऽधिम् १०. ७, २३[२]; १२. १, ४४; ३, ४२; ४६; ४, १७; १९. २७, ९.
निऽधिषु १८. ३, ४५.
निधी इति निऽधी ११. ७, १०.
निऽधीन् १८. ४, ४१; २०. १६, ६.
निनाय ९. २, १७.
निनाय ५. १७, २; २०. १६, २.
निनीषति १९. ५०, ५.
निन्दाः ११. १०, २२.
निन्दिषत् २. १२, ६.
निऽपतन्ती १२. ७, १५.
निऽपतिता १२. ७, १५.
निऽपतितायै ६. ९०, ३.
निऽपद्यते ८. ६, ७; २०. ९६, १५; १६.
निऽपिष्टासः १०. ४, १३; २०.
निऽपुरः १८. २, २८.
निऽपूतः २०. ५, ५.
निऽपृणामि १८. २, ३०; ४, ४२.
निऽप्रियायते १२. ४, ११; २१; २५.
निऽबर्हयः २०. २१, ७.
निऽमज्य १०. ४, ४.
निऽमन्युः ३. २५, ४.
निऽमिता ३. १२, ५; ९. ३, १६.
निऽमिताः ४. ३५, ४.

निऽमिताम् ९. ३, १९[२].
निऽमिमार्य ९. ३, ११.
निऽमिषः ४. १६, ५.
निऽमिषत् १०. ८, २; ११.
निऽमिषतः ४. २, २; ९. २, २३.
निऽमीयते ९. ३, २१; १२. १, ३८.
निऽमीवन्तीम् ५. ७, ७.
निम्नाऽइव २०. १५, २.
निऽम्रुक् ४. ३, ६.
निऽम्रुचः १३. ३, २१.
निऽम्रोचन् २. ३२, १.
निऽयन्ति ६. ४९, ३.
निऽयानम् ६. २२, १; ८. २, १०; ९. १५, २२; १३. ३, ९; १८. ४, ४४.
निऽयुतः २०. १२, ४.
नियुत्ऽभिः २०. ३६, ११.
निऽयोजनम् ७. ८३, १.
निऽरिणाति २०. ३५, १३.
निऽरुध्यते ५. १७, १२; १३; १४; १५; १६; १७.
निऽरुन्धानः २०. २१, ४.
निऽरुन्धानस्य १२. ४, ३६.
निरेके २०. ५२, २; ५७, १५.
निऽरोधनम् १२. ४, १५.
निऽलयते ११. २, १३.
निऽलायन् ४. १६, २.
निऽलिम्पाः ३. २६, ५.
निऽलीनः ४. १६, ३.
निऽवतः ६. २२, ३.
निऽवता ५. ३, २.
निऽवर्तनम् ३. ६, ७; ६. ७७, २; ७. ३९, १; ९. २, १२.
निऽवाते ६. ५५, २.
निऽवाशाः ११. ११, ११.
निऽविदः ५. २६, ४; ११. ९, १९.
निऽविद्धा ९. १४, ८.
निऽविशन्ते ९. १४, २१.
निऽविष्टः ७. ४१, १; १८. २, ३२.
निऽविष्टम् ९. १, २; १०. ८, २४; १८. ३, ९.
निऽवृता २०. १५, ६.
निऽवृत्य १०. १, १७.
निऽवेशनः १०. ८, ४२.
निऽवेशनम् ६. १०६, २.
निऽवेशनी ९. ३, १७; १२. १, ६; १८. २, १९.
निऽवेशने २०. ३७, ५.
निऽवेष्यः ९. १२, ४.
निषङ्गिऽभिः १९. १३, ४.
निष्कऽग्रीवः ५. १७, १४.
निष्कम्ऽइव ५. १४, ३; १९. ५७, ५.
निष्काः ७. १०४, १.
निष्टिग्र्यः २०. १३७, २.
निष्ट्यः १. १९, ३; ३. ३, ६; ६. ६, ३.
निष्ट्याःऽइव २०. ११६, १.
निऽसत्ताः १८. १, ४६.
निऽसत्सुम् २०. ९६, १३.
निऽसद्य १२. ३, २२; १८. १, ५२; ५९.
निऽसिञ्चन् ४. १५, १२.
निऽसीदथः २०. १४२, ६.
निऽसेचनम् १. ३, १; २; ३; ४; ५.
निऽसेदुः ५. १७, ६; ९. १५, १८.
निऽसेदुषः २०. १२६, १६; १७.
निऽस्थितः १९. ३२, ३.
निऽस्थितम् १४. २, ६२; १९. ३४, ६
निऽस्वरः १२. २, १४.

निऽस्वरम् ८. ४, ९.
निर्हः २. ६, ९.
निऽहन्ति ६. ८, २.
निऽहन्यते ६. ७०, १; २; ३.
निऽहितः ६. ९२, २; १४०, २; ७. ६४, १; ११. १, ५; १९; १२. ३, ४२; ४, १४; २९; १८. ३, ७०,
निऽहितम् ६. ११३, ३; ९. १४, ५; १०. २, १९; ८, ६; ९; ११. ९, १०; १२. १, ६०; ३, ४८; ४, १७; २१; १९. २७, ९.
निऽहिता १. १३, ३; २. १, २; ९. १४, ३; ६; १५, २७; १०. १, २९; ११. ९, २२.
निऽहिताः ४. ३९, ६; ७. ४४, १.
निऽहितान् १८. ४, ४१.
निऽहितौ ११. ७, १०.
नीचैः ११. १, ६.
नीचा १. २१, २; ४. ३, ६.
नीचीः ४. १९, १२.
नीचीनम् ६. ९१, २.
नीचीनस्य ७. ५८, ९.
नीचैः २. ३, ३; ३. १९, ३; ४. १, ३; ५. ११, ६; ९. २, १; ९; १५.
नीडे ५. १, ६.
नीताम् ५. १७, ९.
नीनाहम् १९. ५७, ४.
नीयमानाम् ५. ७, १; १८. ३, ३.
नीयसे ५. ४, ८.
नीलऽनखेभ्यः १९. २२, ४.
नीलम् १४. २, ४८; १५. १, ७.
नीलऽलोहितम् १४. १, २६.
नीलऽलोहिते ४. १७, ४.
नीलऽलोहितेन ८. ८, २४.
नीलऽशिखण्ड २. २७, ६.
नीलऽशिखण्डः ६. ९३, १.
नीलऽशिखण्डेन ११. २, ७.
नीलागलसाला ६. १६, ४.
नीलेन १५. १, ८.
नीविऽभार्यौ ८. ६, २०.
नीविम् ८. २, १६; १४. २, ५०.
नीषाट् ५. २०, ११.
नीहारः १८. ३, ६०.
नीहारान् ६. ११३, २.
नु २. ५, ५; ३. २०, ८; ४. १, ६; १९, १; ५. १, ८; २, ४; ६, ५; ११, २; ४; ९; २६, ८; ९; ३०, १; १४^{२}; ६. ४, १; ६०, २; १२४, १; ७. ५, ४; ७, २; २७, १; ९१, १; ८. ९, २१^{२}; ९. १५, १०; १०. २, २; १०; २८^{२}; १२. २, २३; ४, ४३; १०, ४; १४. २, २९; १५. ३, १; १८. १, ५; २०; ४८; २, ५७; १९. ४७, ५; ५३, २^{२}; ३; ५४, ५; २०. २१, १; २४, २; ३२, १; ३६, ५; ३७, ९; ११; ५०, १; ५९, ३; ६३, १; ६५, १; ७१, १; ७३, २^{२}; ५; ७६, ६; ९७, ३^{२}; १०७, ७; १२४, ४; १२६, ३; ४; ५; १४३, ६.
नुत्ता १०. १, १४.
नुत्ताऽइव १०. १, ३.
नुत्ताः ८. ८, १९.
नुत्तानाम् ९. २, ४.
नुद २. २५, ५; ३. १८, २; ६. १३९, ३^{२}; ७. ३५, १; १२. २, ४२; १४. २, ६४.
नुदत ६. २८, १; १२. २, ३०.
नुदतम् ६. ३२, ३.

नुदताम् ९. २, १५; १२. १, ४१; ११, ११; १२; १७. १, ३०.
नुदतु १. ७, ४; ६. ७५, २.
नुदते १९. ३६, २.
नुदन् ३. १५, १; १९. ३३, २.
नुदन्तु ६. १२४, २; १२. ३, ४९.
नुदस्व ९. २, ४; ११. १, २१.
नुदस्व ४. ३१, २; ७. ३५, १; ३६, १; ८९, ३; ९. २, ४; १७; १८; १२. ३, २१; १३. १, २७; २०. १२५, १.
नुदामः १२. ३, ४३.
नुदामः १०. १, १; २.
नुदामसि १२. २, १५; १६.
नुदामहे ३. ६, ८.
नुदिष्ठाः १२. १, ३२.
नुदे ३. ६, ८; ६. ७५, १; ९. २, ६.
नुदेथाम् ८. ४, १.
नुदेथे इति ४. २९, १; २.
नुनुदे २०. ११, १०.
नुनुदे २०. २८, २; ३९, ३.
नुवन्तम् २०. ७४, ५.
नूतनः २०. १७, ५.
नूतनम् ७. २२, १.
नूतना २०. ८७, ५.
नूनम् ४. १, ६; ७. ७७, २; ८. ४, २०; १८. १, ४; ४६; २०. ६६, २; ९७, १; १३९, १; १४०, २; ३; १४१, ४; ५; १४२, ६.
नृऽचक्षः १. ७, ५; ४. १६, ७; ८. ३, ९; १७.
नृऽचक्षसः ८. ३, ८; १३. २, १; १८. ४, २९; १९. ४७, ३.
नृऽचक्षसा १८. २, १२.
नृऽचक्षसि १०. ३, १८.
नृऽचक्षसौ ४. २९, २.
नृऽचक्षाः ७. ४२, १; २; ८. ३, १०.
नृणाम् २. ९, २; १९. ४७, ७; २०. ३७, १०; ७६, १; २.
नृतः १०. २, १७.
नृऽतम २०. ३७, १०.
नृऽतमः २०. ७६, १; ७७, ४.
नृऽतमम् २०. ११, ११.
नृऽतमस्य २०. ७६, २.
नृऽतमाय १८. १, ३७.
नृतये १२. २, २२.
नृतौ २०. ७६, २.
नृत्तानि ११. १०, २४.
नृत्य ५. २०, १०.
नृत्यतु १०. ९, २.
नृत्यन्ति १२. १, ४१.
नृत्यन्ति १२. १०, २.
नृऽपतिम् २०. ९४, ३.
नृपती इवेति नृपतीऽइव ८. ४, ६.
नृऽपते ५. १८, १; १९; २०. ९४, २.
नृऽपानः १९. ५८, ४.
नृऽपाय्यम् २०. १४२, ३.
नृऽभिः ३. १६, ३; ५. १३, ३; १८. ४, ६५; २०. १६, १२; ३३, १; ३७, ४; ५६, १; ७३, १; ८७, ४; १२०, १.
नृऽभ्यः २०. ७७, ४.
नृऽमनः २०. ३७, ४.
नृऽमनाः १६. ३, ५; २०. १३७, ७.
नृऽमादनम् २०. ६८, ७.
नृम्णम् ४. २४, ३; ८. ५, २१; १०. ५, १; २; ३; ४; ५; ६; २०. १०८, १; १३९, २.

नृम्णऽवर्धनः २०. ६७, ६.
नृम्णस्य २०. ३४, १.
नृऽवत् २०. ११, ५.
नृऽवतः २०. ३६, ३.
नृऽवन्तः ३. १६, ३.
नृऽवाहसा २०. २६, ५; ४७, ११; ६९, १०.
नृऽसहम् २०. ४४, १.
नृऽसह्याय २०. १४२, ५.
नृऽसूतः २०. १२०, १.
नृन् १८. १, ७; २०. ७६, २; ४.
नेक्षणम् ९. ६, १७.
नेता १९. १३, ९; २०. ३४, ७; ७७, ८; ९२, १०.
नेतारः १०. ८, ३५.
नेत्रम् १०. १०, २२.
नेदिष्ठम् २०. ८५, ४.
नेदीयः ३. १७, २; १०. ८, ८.
नेदीयसः २०. १२६, २०.
नेनिग्धि ९. ५, ३.
नेमिम् २०. ९४, ३.
नेमे २०. १५, ५.
नेशत् ५. ३, २; १३, २.
नेष ७. १०२, २; १२. ३, १६.
नेषत् ६. ११०, २; ७. १०, २; १२. ३, ५५; ५६; ५७; ५८; ५९; ६०.
नेषि १९. १५, ४; २०. ४६, ३.
नेष्ट ३. ११, ७.
नेष्यति ७. १०८, १.
नैःऽऋतेभ्यः १९. ४५, ५.
नैःऽबाध्येन ६. ७५, १.
नैःऽहस्तम् ६. ६५, २; ३.
नैदाघः ९. ५, ३१.
नैदाघम् ९. ५, ३१.
नो इति १. ३२, १; ३. १८, ३; ३०, ४; ८. २, २४; १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५; २०. १२६, २.
नोदनाय ७. १२१, १.
नोधाः २०. ३५, १४.
नोनुमः २०. १८, ४; १२१, १.
नौ ५. ११, १०^{२}; ७. ३७, १^{३}; ११. १, ३५; १३. १, १८; १४. २, ७२; १८. १, ४^{२}; ५^{२}.
नौः ५. ४, ४; ६. ९५, २; १९. ३९, ७.
नौःऽइव ३. ६, ७; ९. २, १२.
नौधसम् १५. २, २२; ४, ११; १२.
नौधसस्य १५. २, २४.
नौधसाय १५. २, २३.
न्यः ११. ९, ४.
न्यक् ६. ९१, २^{३}; २०. १२०, १.
न्यग्रोधाः ४. ३७, ४.
न्यग्रोधात् ५. ५, ५.
न्यङ् ५. २२, २.
न्यर्धुः १९. २०, १.

प

पक्तवे ११. १, ३.
पक्ता ११. १, १७; १९.
पक्तारः १०. ९, ७; ११. ३, १७.
पक्तारम् १०. ९, ११; २५; १२. ३, ४८.
पक्त्वा ४. ३४, ५; ११. १, १८; ३७.
पक्वः ९. ५, १८; १२. ३, ४८.
पक्वम् ३. १७, २; ६. १२२, ३; ११. १, २८; ३३; १२. ३, ७; ११.
पक्वा १२. ८, ५; २०. ६०, ४; ७१, ४.
पक्वात् ४. ३५, ६; १२. ३, २; ९.
पक्वाय १२. ३, ८.

पक्केन ६. ११९, २; १२. ३, ३४; ५५; ५६; ५७; ५८; ५९; ६०.

पक्षः १३. ३, १२.

पक्षत् २०. ९२, १२.

पक्षसी इति ८. ८, २२.

पक्षाणाम् ९. ३, ४.

पक्षिणः १. ११, ६; ११. ७, २१; ८, ८; १२, ८; १२. १, ५१.

पक्षिणी ६. २७, २; ३.

पक्षी ४. ३४, ४; ७. ८०, ४; १३. २, ३३.

पक्षौ ४. ३४, १; ६. ८, २; ८. ९, १४; १०. ८, १८; ९, २५; १३. २, ३८; ३, १४.

पङ्क्तिः ९. १५, २१; १३. १, १५; ४२; १९. २१, १.

पङ्क्तिम् १३. ३, २५.

पङ्क्त्या १३. ३, ५.

पचत ९. ५, ३७.

पचत १२. ३, २७.

पचतः ११. १, ३०; १२. ३, १२; ५०.

पचतम् २०. ३५, ७.

पचति १०. ९, ४; १२. ३, ४; ५; ३९.

पचति ११. १, १.

पचते १२. ४, ३८; ५३; २०. ३४, १८.

पचन् १२. ३, २४.

पचन्तम् २०. ३४, १५.

पचन्ति ४. ३४, ३; ४; ९. ७, १३; २०. १२६, १४.

पचामि ४. ३५, ७; ६. १२३, ४; १२. ३, ४७.

पच्यमानम् २०. ९२, ११.

पच्यमाना ५. १९, ४; १२. ८, ५.

पञ्च १. ३०, ४; ३. ४, २; २०, ९; २१, ५; २४, ३^{2}; ६. २५, १; ७५, ३; ७. ६, १; ८. ९, ४; १५^{4}; २३; ९. ५, २५^{3}; २६; ३७; १०. ८, ३५; ११. २, ९; ८, १५; २२; १२. १, १५; ४२; १३. १, १८; ३, ६; १८. ४, ५५; १९. ९, ५; २२, १; ४७, ४; २०. ७०, १५; १३९, २.

पञ्च ५. १५, ९.

पञ्चऽअङ्गुरिः ४. ६, ४.

पञ्चऽअपूपम् ३. २९, ४; ५.

पञ्चऽअरे ९. १४, ११.

पञ्चऽऋचेभ्यः १९. २३, २.

पञ्चऽओदनः ९. ५, ८; ९; १०; १८; २१; ३१; ३२; ३३; ३४; ३५; ३६.

पञ्चऽओदनम् ४. १४, ७; ९. ५, ११; १२; २२; २४; २५; २६; २७; २८; ३१; ३२; ३३; ३४; ३५; ३६.

पञ्चऽदश २०. १२६, १४.

पञ्चदशऽऋचेभ्यः १९. २३, १२.

पञ्चऽदशः ११. १, १९.

पञ्चऽदशेन ८. ९, १५; २०.

पञ्चऽधा ४. १४, ७; ९. ५, ८.

पञ्चऽनाम्नीम् ८. ९, १५.

पञ्चऽपादम् ९. १४, १२.

पञ्चऽपादात् ८. ६, २२.

पञ्चऽबिलम् ११. ३, १८.

पञ्चऽभिः ४. १४, ७; १७. १, १७.

पञ्चऽभ्यः ५. १७, ९.

पञ्चमः १३. ५, ४; १५. १५, ७; १६, ५; १७, ५.

पञ्चऽयोजनम् ६. १३१, ३.

पञ्चऽरात्रः ११. ९, ११.

पञ्चऽवाही १०. ८, ८.

पञ्चऽवृषः ५. १६, ५.

पञ्चऽशलात् ८. ७, २८.
पञ्चऽसु २०. २०, २; ९७, ९.
पञ्चाशत् ५. १९, ९; ६. २९, १; १९. ४७, ४.
पट्टरैः १३. ३, १६.
पट्टरौ ११. ११, १४.
पड्वीशम् ८. १, ४.
पड्वीशात् ६. ९६, २; ७. ११७, २; ८. ७, २८; १६. ८, ३२.
पड्वीशे १२. ७, ४.
पणयः ५. ११, ६; १९. ४६, २.
पणिम् २०. ९१, ६.
पणीन् ४. २३, ९; ५. ११, ७; २०. ३७, ९; ९३, २.
पणेः २०. २९, ४.
पणौ २०. ९९, ३.
पण्डगाः ८. ६, १६.
पत १. ११, ६; ३. ३, ३; १०, ७[2]; १९, ८; ६. १४, ३; १०९, १; २; ३; ७. १२०, १[2]; १४. २, १९.
पतङ्ग ६. ५०, २; १३. २, ३०.
पतङ्गः ६. ३१, ३; १३. २, ३१; ३, १; २०. ४८, ६.
पतत ६. ८३, १.
पततः १०. ८, १८; १३. २, ३८; ३, १४.
पतति ४. २०, ९; १०. ८, ११.
पतति ६. ८०, १; ७. ८०, ४.
पततु ५. १४, १२; ११. १२, ७; २०.
पतत्रिणः १. १९, १; ५. २१, ६; ८. ७, २४; ११. ११, ९; १२, २४; १९. १, १.
पतत्रिणी ५. ९, ९; ६. २९, १.
पतत्रिऽभिः १०. १०, १४.
पतत्रीऽइव १४. २, ४४.
पतत्रैः १३. २, २६.
पतन्तम् ८. ३, ५; १३. २, ३६; १८. ३, ६६.
पतन्ति १. ११, ६; २०. ९२, ७.
पतन्ति ६. २२, १; ९. १५, २२; १३. ३, ९.
पतन्तु १. १९, २; २. ३, ६; ६. १२६, ३.
पतयः ३. १०, ५; ४. ३७, १२; ५. १७, ८; ६. ६२, २; ७. ८४, ४; ८५, ३; ९६, १; ११४, ६; ९. १२, १४; १०. १, २२; ९, २७; १९. ११, १; २०. ८८, ६; १२५, ६.
पतयत् २०. ६८, ७.
पतयत् २०. १७, ८.
पतयति १९. ४८, ३.
पतयन् १३. २, ३१.
पतयन्तम् १३. २, २; १८. ३, १८; २०. ९६, १३.
पतयन्ति ८. ४, १८.
पतयन्ति ८. ४, २०.
पतयालुः ७. १२०, २.
पतयिष्णुकम् ६. १८, ३.
पतये २. ८, ५; ३. १०, ९; १०; १९ ३७, ४.
पताति ५. २९, २; ३; २०. ७४, ६.
पतिः १. १, १; ३; ४[2]; २१, १; २. २, १; २; ३६, ८; ३. ४, १; १०, ८; ४. २, ७; ५. ३, ९; १७, ८; ९; ६. ४, १; ५, ३; ३३, ३; ७३, ३; ७४, १; ७९, १; ८७, ३; ७. १८, १; ३१, १; ८. ५, २२; ९. ४, २; ४; १७; ५, २८; ११. ११, २५; १२. २, ६; ३९; ३, ३९; १३. १, ५१; ३, ७[2]; ८, २; १४. १, २६; २७; २, २; ३[2]; ६३; १६. ६, ६[2]; १८. १,

३; १९. १०, ५; १०; २०, २; २०. २१, २; ६४, १; २; ३; ७३, ४; ७७, ७; ९१, ७; ९६, १५; १२६, ११; १३७, ५; ६; १४३, ८.

पतिऽकामा २. ३०, ५.

पतित्वा ४. १२, ७.

पतिना १६. ६, ६^{२}.

पतिऽभ्यः २. ३६, ७; ५. १२, ५; १४. १, ४६; ६१; २, १; १२.

पतिम् २. ३६, ३^{२}; ३. १६, १; १८, १; २; ५. १, ४; ६. ३६, १; ६०, १; ३; ७८, ३; ७. २२, १; ४८, ३; ९. ५, २७; ११. ७, १८; ८, ४; ११, ८; १२. ३, २९; १४. १, ६; १०; १२; २५; ३१; ५९; २, २२; ५२; १८. १, ११; १९. ३०, ३; २०. १७, १; २३, ५; ६४, ६; ७१, १०; ९४, ४.

पतिम्ऽइव १८. २, ५१.

पतिऽलोकम् १४. २, ४०; १८. ३, १.

पतिऽलोके १४. १, ६४.

पतिऽवेदनम् २. ३६, २; १४. १, १७.

पतिऽवेदनौ ८. ६, १.

पतिष्यति ६. ८३, ३^{२}.

पती इति ६. ३, ३.

पती इति ६. ६९, २; ९. १, १९; १४. १, १५; २, ५; ६; २०. १२५, ४.

पते १. १, २^{२}; २९, १; ३. २०, २; ४. ४, ६; १९, ८; ६. ६, १; ४५, ३; ७९, २; १०१, २; १४०, १; ७. ५८, ४; ७८, ३; ८६, ३; १०२, ८; ८. ६, १५; १०. ५, ४५^{२}; १३. १, १७; १८; १९; १४. १, ३१; १९. ८, ६; २४, १; ६३, १; २०. ४५, २; ६०, ३; ७४, २; ७५, २; ९६, २४.

पतौ ३. १८, ३.

पत्ऽघोषैः ५. २१, ८.

पत्ततः ६. १३१, १.

पत्तीन् ७. ६४, १.

पत्थाः ८. १, ४; १०.

पत्नि ३. १२, ५; ७. ४८, ३; ९. ३, ९.

पत्नी २. १२, १; ३. १०, २; ७. ४९, २; ९. ३, ६; १२. १, १; १४. १, ५१.

पत्नीः २. २६, ५; ७. ५१, १; ९. १२, ६; १४. २, ३२.

पत्नीनाम् ९. ३, ७.

पत्नीनाम् १९. ५७, ३.

पत्नीभिः ५. २६, ४; ११. ८, १९; २०; १४. २, ५१; १९. ५८, ६.

पत्नीम् ७. ६, २; ९. ३, २१; १४. १, ४९; २, २.

पत्नीऽवतः २०. १३, ४.

पत्न्याः ९. ३, ५.

पत्ऽभिः ३. ७, २; ४. ११, १०; १४, ९; १९. ६, २.

पत्ऽभ्याम् ५. ३०, १३; १२. १, २८; १९. ६, ६; ८.

पत्यते २०. ३६, १; ६७, ७.

पत्यते २०. ६३, ६.

पत्यमाने इति ५. २७, ८.

पत्या २. ३६, १; ४; १०. १, ३; ११. १, १४; १४. १, २१; ४०; ५०; ५२; २, ३२.

पत्याऽइव ६. २२, ३.

पत्युः १४. १, ४२; ४३; १८. ३, २.

पत्ये ३. ३०, २; ८. ६, २१; १४. १, ९;

४९; ५५; २, ७; २४; २६; २७; ३१; १८. १, ८; २०. ३५, २.
पत्ये॑ते इति॑ ७. २६, १.
पत्ऽवता॑ १०. १०, १३.
पत्ऽवती॑ ९. ३, १७; १४. १, २५.
पत्ऽवती॑नाम् ९. १५, २३.
पत्ऽसङ्गिनी॑ः ५. २१, १०.
पत्सि॒ ६. १२०, २.
पत्ऽसु ६. ९२, १.
पथः ५. १२, २; २७, २; ३०, ७; ६. ११७, ३; १२१, ४; ८. २, १०; १०. ४, ६; ११. १, ३६; १३. १, ५९; १५. ११, ३; २०. २५, ५.
पथा ३. १८, ६; ४. ३, २; ५. ३१, १०; ६. ७, १; ८२, २; १८. १, ६१; २, ११; ४६; ४, ६०; २०. १२६, २१.
पथाम् ४. ३, ५; ५. १, ६; ६. २६, २; ७. १०, १.
पथि १४. १, ६३.
पथिऽकृत॑ः १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.
पथि॑ऽकृता १८. २, ५३.
पथिकृत्ऽभ्य॑ः १८. २, २.
पथिऽभि॑ः २. ३४, ५; ९. ४, ३; १५, ११; १२. २, १०; २९; ४१; १८. १, ५४; २, ५३; ४, २; ३; ६२; ६३; १९. २७, ९; ४७, ७.
पथिरक्षी इति॑ पथिऽरक्षी॑ ८. १, ९.
पथि॑ष्ठः ६. २८, १.
पथिसदी इति॑ पथिऽसदी॑ १८. २, १२.
पथि॑ऽस्थाम् १४. २, ६.
पथीनाम् ९. ५, १९.
पथ्या॒ऽइव १८. ३, ३९.
पथ्या॒ः ३. ४, ७; १८. १, ५०.
पदः ४. १५, १४; ९. ४, १४; ५, ३.
पद्ऽज्ञाः ७. ७९, २.
पद्नीःऽइ॑व ११. २, १३.
पदम् २. १२, ८; ३. १०, ६; ६. २७, ३; २९, १; ७०, २; ७६, २; ३; ७. २७, ७; ९. १४, ५; १५, १; १९; १०. १, २६; ४, २४; ८, ६; १२. २, ३०; १८. ४, ८९; २०. ९१, २.
पद्ऽयोप॑नीम् ५. १९, १२.
पद्ऽयोप॑नेन १२. २, २९.
पद्ऽवायः ५. १८, १४.
पद्ऽवायम् १२. ५, ४.
पद्ऽवीः १२. १०, १२.
पदा ७. २७, ४; ५; ८. ६, १७; ९. १४, ५; १७; १०. ४, ३; ७; १३. १, ४१; ५६; २०. ६३, ५; ९३, २.
पदात् ६. २८, १.
पदानि॑ २. १, २; ६. २८, १; ९. १४, ६; १५, २७; १२. २, २८; १८. ३, ४०.
पदाय॑ ३. १६, ६.
पदीष्ट ७. ३२, १; ८. ४, १६; १७.
पदे ६. ६३, ४; ७. २८, १; २०. ९२, ४.
पदेन॑ ६. ७०, २.
पदेऽप॑दे ५. ६, ३.
पदोः १. १८, २; १२. ४, ५.
पद्यताम् १. ११, ४; ५; ६; ४. १८, २; ६. २६, २; १०. ९, २७.
पद्यते ११. ६, २५; १८. ३, १.
पद्यन्ताम् ३. १९, ३; ८. ८, १८; २०; १३. १, ३१.

पद्यस्व ३. १९, ८; ११. १२, १८.
पद्ये ५. ६, ११; १२; १३; १४; १९. ८, २[२].
पनयन्ति २०. ११, ६.
पनस्यते २०. ५८, ३.
पनस्यवे २०. ६२, ५.
पनाय्यम् २०. १४३, ९.
पनिप्रतम् ७. ३३, १.
पनिष्पदा ५. ३०, १६.
पनीयसी १८. ४, ८८.
पनीयसे २०. १५, ३.
पन्थाः ४. २, ३; १०. १, १५; १३. १, २३; १४. १, ११; १८. ४, १४.
पन्थानः ३. १५, २; ३१, ४; ५. ४, ५; ६. ५५, १; ७. ५७, २; १२. १, ४७; १४. १, ३४.
पन्थानम् १२. १, ४७.
पन्थाम् ३. ३, ४; ६. २८, ३; ८. १, १०; ९, १३; १२, ४; ६; ११. १, २८; ३०; ३१; १२, १६; १२. २, २१; ५५; १४. १, ५८; २, ८; ७४; १५. १२, ५; ९; १७. १, १६; १८. १, ४९; ३, ४; ४, ३; १९. ५९, ३; २०. ६३, ९.
पन्नानाम् ९. २, ९.
पपत्यात् ६. २९, ३.
पपन २०. १८, २.
पपार्च ४. ३५, २.
पपात ७. ४४, १.
पपाथ २०. ८७, ३.
पपिऽवांसः ७. १०२, ३.
पपिऽवांसम् १८. १, ४८.
पपिऽवान् १४. १, ३; २०. ३५, ७.
पपुरि २०. ८०, १.
पपुर्षः २०. ९४, २.

पपृक्षे २०. १४३, ७.
पपृच्याम् १८. १, १३; १४.
पपौ ४. ६, १.
पप्तत् ७. ५४, २.
पप्तम् १२. १, ३१.
पप्रथत् २०. ११८, ४.
पप्रथाना १२. १, ६१.
पप्रथे १९. ३, ३.
पप्रथे २०. १०४, २; ११९, २.
पप्राथ २०. ८१, २; ८७, ३; ९२, २१.
पप्रिः २०. ४६, २.
पप्रिम् १२. २, ४७.
पप्रे ११. २, २७.
पप्रौ १९. ४९, १; २०. ७७, ५.
पयः १. ४, १; २. २९, ५; ३. ५, १; १७, ७; २९, ६; ४. ८, १; ११, ४; २७, ३; ६. ६९, ३; ७. ७७, ४; ६; ८; ८. २, १९; ३, १७; ९. १, २; ८, २; १५, ५; १०. ६, ३१; १०, १०; ३१; ११. ७, १४; १२. १, ९; १०; ६, ४; १४. २, ५७; १८. २, ३; ३, ५६[२]; १९. ३१, ५; ४३, ५; ४४, ५.
पयःऽभिः ९. १, ८; १५, ६.
पयःऽस्फातिम् १९. ३१, १०.
पयते ९. १, ८; १५, ६.
पयसः ७. ७७, ५; १८. ३, ५६.
पयसम् ४. १४, ६; ७. ४०, १.
पयसा १. ३५, ४; ३. १५, २; १७, ९; ४. ८, ५; १४, ६; १५, ६; ५. १, ९; २८, ३; ६. ५३, ३; ६२, १; ७८, २; १२४, १; ७. ७७, ६; ८४, ३; १०. १, १२; ६, २६; ११. १, ७; १२. १, ५९; १३. १, ८; ९; १४. २, ७०[२].

पय॑स्वत् ३. २४, १; १८. ३, ५६.

पय॑स्वती ३. १०, १; १२, २; १७, ४; ४. ३८, ३; ९. ३, १६; १२. १, ५९.

पय॑स्वती इति॑ ६. ६२, १.

पयस्वती इति॑ २. २९, ५.

पय॑स्वतीः ३. २४, १; ४. ८, ४; ६; ६. २२, २; ८. २, १४; ७, १७; १८. ३, ५६.

पय॑स्वतीनाम् ३. २४, १.

पय॑स्वतीम् १३. १, २७.

पय॑स्वन्तः ७. ६२, २.

पय॑स्वन्तम् ३. २४, २; ६. ५९, २.

पय॑स्वान् ७. ७७, ५; ९४, १; ९. १, १४; ४, १; ३; ९; १०. ५, ४६; १९. ३३, १; २; ४६, ६[2].

पयां॑सि १. ९, ३; ५. २६, १०; १८. १, १८.

परः॑ ९. १५, १४; १८. २, ३२.

परः ३. ८, ४; ४. ३०, ८[2]; ५. ७, ७; ११, ५; ६[2]; ६. ४५, १; ७. ८, १; ८. २, १२; ४, ११; ९. ४, २१; १४, १७; १८; १५, २५; १०. ७, २५; ११. १, २९; २, ११[2]; ७, १०; १३. १, ४१; १४. १, ३२; १८. ३, ७; २०. ७१, १; ९१, ४; ९२, ११; ९६, २४[2].

परःऽतराम् ५. २२, ७; ३०, ९; ६. ६७, १.

परःप॑रः १२. ३, ३९.

परःऽपा २०. १४१, १.

परःऽसहस्राः ८. ८, ११.

पर॑म् १. ८, ३; ७. ३६, ३; ८. ३, ३; ९. १५, १३; १०. ७, ३१; ८, ८; ११. १, ३०; १२. २, २१; १८. २, ३२; १९. ५३, ४.

परमः १९. ५४, ५.

परमऽज्याः २०. १०४, ३.

परमम् १. १३, ३; २५, १; २. १, १; २; ५. ११, ११; ७. २७, ७; ९. १५, १३; १४; १०. ७, ८; २८; ११. १, ३०; १४. २, ३६; १८. १, ४; १९. ५४, ५.

परमम्ऽइ॑व १०. ७, २१.

परमस्य॑ १३. ३, ५.

परमस्याः॑ ३. ४, ५.

परमा २०. ८८, ३.

परमात् ७. ६५, १.

परमान् ६. १०३, २.

परमाम् ६. ७५, २; १५. ६, १३.

परमे ५. १७, ६; ६. १२३, १; २; ७. ५, ३; ८. ९, ८; ९. १५, १८; १२. १, ८; २, ७; १३. १, ४४; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १८. ३, ७; ५८; ४, ३८; १९. ५३, ३; २०. ८८, ४.

परमेण॑ ४. ३, २; १९. ५६, ५.

परमेभिः॑ १९. ४७, ७.

परमेऽस्थिन् १. ७, २; १३. १, १७; १८; १९.

परमेऽस्थिन॑ः १०. ५, ४२; १५. ६, २६.

परमेऽस्थिन॑म् १०. २, २०; २१; ७, १७[2]; ११. ७, ७; १९. ९, ४; ५३, ९.

परमेऽस्थिनि॑ १०. ३, २४.

परमेऽस्थिनी॑ १९. ९, ३.

परमेऽस्थी ४. ११, ७; ८. ५, १०; ९. ३, ११; १२, १; १२. ३, ४५; १३. १, ६; ३, ५; १५. ६, २५; ७, २; १४, २३.

परशुः ७. २९, १[2]; ८. ४, २१; २०. १७, ९.

परशून् ११. ११, १.

परशोः ३. १९, ४.

परस्तात् **४.** १६, ४; ५; **६.** ७३, ३; १२२, १; ४; **७.** १०, ४; **८.** १, १०; **१०.** ७, ४३; ८, ३९; **१३.** २, ८; ३१.

परस्फानः **१९.** १५, ३.

परस्मात् **३.** ३, ४.

परस्मिन् **६.** ११७, ३.

परस्मै **१.** १२, ४.

परस्य **१३.** ३, ५.

परस्याः **६.** ३४, ३; **७.** २७, २; ८९, ३.

परस्वतः **६.** ७२, २.

परस्वन्तम् **२०.** १२६, १८.

परा **१.** २३, २; **२.** २, ३; **३.** २, ५; ४, ६; १०, ७; १८, २; १९, ८; **४.** १३, ५; २०, १; ३७, ३; ४; ५; **५.** ३, ८; १४, ४; १८, १०; १२; १९, १; ६; ११; २१, ७; २२, २; ३; २८, ६; **६.** २९, ३; ४५, १; ६६, २; ७५, १; ९८, १; १२७, ३; १४०, ३; **७.** १०, १; ४५, १[२]; ५५, ४; ६; १०५, १; **८.** ३, १३[४]; १४; १६[२]; ४, १; ५, ३; ९; ८, २४; **९.** १४, १७; १५, ११; **१०.** १, ७; १६; २०; २४; २५; २६; ४, २०; ५, ४९[४]; **११.** १, ११; १३; **१२.** १, ३७; २, १; २१; ५५; ४, ४९; ९, ५; **१३.** १, ४१; **१४.** १, २५; २, ३४; ३५; **१६.** ४, ३; ६, ३[२]; ७; ११; **१८.** ३, १४; ६२; ४, ६३; **१९.** ८, ४; ३९, १०; **२०.** ६८, ४; ७७, ७; ९६, ३; १२६, २.

पराऽअपतत् **१.** ३, ९.

पराऽअयनम् **१.** ३४, ३; **६.** ७७, २; **१०.** ४, ७.

पराऽअयने **६.** १०६, १.

पराऽअवधीत् **१०.** ६, ३.

पराऽइतः **३.** ११, २; **४.** ३२, ५; **१८.** २, २६; **२०.** ९६, ७.

पराऽइतम् **१८.** ४, ५१; ५२.

पराऽइताः **१२.** २, २९; **१८.** १, ५०; ५४; ४, ४४.

पराऽइत्य **५.** २२, ८; **१०.** ४, १९; **१४.** १, ४३.

पराऽईयुः **२.** २६, १; **१८.** २, ४७.

पराऽउप्ताः **१८.** २, ३४.

पराक् **१०.** १, १६.

पराके **२०.** १४१, ५.

पराक्ऽमनाः **८.** १, ९.

पराऽक्रम्य **१०.** ७, ११.

पराऽक्रान्तः **१०.** ७, १६.

पराऽगतम् **७.** १३, ४.

पराऽगताः **१८.** ३, ७२.

पराङ् **६.** २९, ३; ६७, ३; **१७.** १, १७.

पराचः **२.** २५, ५; **३.** १, ४; **९.** १४, १९.

पराचीना **६.** १०६, २.

पराचीनाय **११.** ६, ८.

पराचीम् **६.** २९, ३.

पराचैः **२.** १०, ५; **६.** ९७, २; १२४, २; **७.** ४३, १; ५५, ३; **८.** ९, २; **१८.** २, २६.

पराऽजयन्ते **४.** २२, ५.

पराऽजिता **३.** १, ६.

पराऽजिताः **५.** २१, ९; **८.** ८, १९.

पराऽजितासः **४.** ३१, ७.

पराञ्चः **४.** ४०, १; २; ३; ४; ५; ६; ७; ८; **९.** १४, १९; **११.** ११, २२.

पराञ्चम् **६.** ६५, १; **११.** ३, २६; २८; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८.

पराऽददिः **२०.** ५६, २.

पराऽद्दश्यं **८.** ८, २.

पराऽदै **२०.** ३७, ७.

पराऽनीयं **१२.** ४, ९२.

पराऽनुदे **२०.** २८, ३; ३९, ४.

पराऽपतंति **६.** १०९, १; २.

पराऽपतंन्ति **६.** १०९, ३.

परांऽपरैता **१८.** ४, ४८.

पराऽपुरः **१८.** २, २८.

पराऽभवेत् **१२.** ४, ४९.

पराऽभुवे **१.** २९, ४.

परांऽभूतिः **१२.** ८, ८.

परांऽभूत्या **१६.** ७, १.

परांऽभूत्याः **१६.** ५, ७; ८, ८.

परांऽभृतम् **५.** २९, ९; १२; **७.** ४२, २; **२०.** ४३, २.

परांम् **३.** १८, ३.

परांऽमृष्टा **१२.** ७, १३.

पराऽयतः **७.** ३९, १.

पराऽयते **११.** २, १९; ६, ७.

पराऽवत् **२०.** ८८, ३.

पराऽवतः **३.** ४, ५; **४.** १३, २; **५.** ३०, १; **६.** ३४, ३; ३५, १; ७५, ३; **७.** २७, २; ८९, ३; **८.** ५, ९; **१०.** १०, २; ३; **१२.** ११, ३; **१८.** ४, ४१; **२०.** ६, ८; २०, ४; ५७, ७.

पराऽवर्तम् **३.** १८, ३; **६.** ७५, २; **८.** १, ८; **२०.** ६, ९.

पराऽवर्ति **२०.** २१, ७; १११, २; ११२, ३.

पराऽवाकार्य **६.** १३, २.

परांऽशर **६.** ६५, १.

पराऽशरः **८.** ४, २१.

पराऽशसां **६.** ४५, २.

परांसः **१८.** १, ४४; ३, २१.

परिं **१.** २, २; १०, १; ४; १४, ३; १७, ४; २०, २; २२, १; २; ३; २५, १; २; ३; ३०, २; ३; ३४, ५; **२.** १, ४; ५; ४, २; ७, ३; ४^{३}; १३, २; ३; १४, ६; ३३, ३; ३४, ५; **३.** २, ४; ११, ७; २५, ५; **४.** ७, ५; ६; ८, ३; ९, ९; १०, १; ४; ११, १२; १५, १०; १९, ८; २१, ७; ३४, ४; **५.** ३, २; ४, २; ६, ४^{२}; ७, १; १४, ३; २२, १०; १४; ३०, ११; **६.** ८, १; ३; १२, १; २७, २; २८, १; २^{२}; ३७, २; ५५, १; ६१, २; ६७, १; ८४, १; ८९, १; ९३, १; ९९, २; ३; १०३, २; ३; १०६, ३; १०७, १; २; ३; ४; १०८, ५; ११०, २; १११, ३; ११२, १; ११६, ३; १२२, १; १२३, १; १२५, २^{३}; १३३, ५; १३७, २; ३; **७.** १०, ४; ३९, २; ४६, १; ५३, १; ५५, ४; ७; ५८, १; ७४, १; ७५, २; ७९, १; ८६, १; ८९, १; १०४, १^{२}; **८.** २, ९; २०^{२}; २२; २६; ३, ३; १०; २०; २२; ४, ५; ६; ६, २१; २२; ९, ४; ५^{२}; १८; **९.** २, ५^{२}; १६^{२}; ४, १०; ५, २; ६; १३, ८; २१; १४, १३; २०; १५, ३; १७; **१०.** १, ३२; २, १५; १८; ३, १०; ४, २५; ७, २५; ८, १७; ३०; ३६; **११.** २, ४; ८^{२}; २०; २५; ११, ५; १२, १९; **१२.** २, ३३; ४७; ३, १६; २५; ३१; ३३; ३५; ४०; ४६; ५१; ५३; ५५^{२}; ५६^{२}; ५७^{२}; ५८^{२}; ५९^{२}; ६०^{२}; ४, ४९; ५२; १०, २; **१३.** १, १७; १८^{२}; १९; २०; २५^{२}; २६; २, ३; ११; ३२; ४३; ४४; ४५^{२}; **१४.** १, २३; ३९; ४५; ५३; २, १; ३९; ४४; **१५.** १, ५; १२, ७; १३,

१३[२]; १७, ८; १७. १, ९; १५; ३०; १८. १, २; १५; १६; १९; ३५; २, ५; १२; २७; ५४; ५५; ५८; ३, १२; ५२; ४, ९; १९. १, ३; ३, १; १३, ८; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; २०, १; २४, १[२]; २; ३; ४; ५; ६; २६, १; ३१, ५; ३२, १०; ३३, १; ३४, ५; ३५, ४[६]; ३७, ३; ३९, १; ५; ४४, ६; ८; ९; ४५, ५; ४६, ३; ४; ४८, १; २[२]; ५०, ७; ५२, ४; ५३, ४; ५७, ५; २०. १६, ८; १७, १; ६; ११; २०, ७; २६, ४; ३५, ८[२]; ९; ११; ३९, १; ४२, १; ४३, १; ४७, १०; ५२, १; ५७, १०; १४; ६३, ३; ६९, ९; ७०, १६; ८९, ११; ९२, ६[२]; ९४, ११; ९५, ३; ९६, १९; ९७, ३; ११०, १; ११५, १; १२४, ६; १२९, ४.

परिऽअभूषत् २०. ३४, १.

परिऽअस्यन्ती १२. ७, १०.

परिऽआकृता १२. ८, ६.

परिऽआक्रियमाणा १२. ८, ६.

परिऽआदधति १२. २, ५१.

परिऽआवृत्त ९. ५, ५.

परिऽआनद्धम् १४. २, १२.

परिऽआयिनः ६. ७६, ४.

परिऽआवर्ते ७. १०५, १; १२. १, ३४.

परिऽआवर्तेथाम् १२. ३, ८.

परिऽआवृतः ११. ६, २६.

परिऽईङ्खयाते १८. २, ५८.

परिऽउक्ता ४. १९, २.

परिऽउह्यमाना १८. १, ५३.

परिऽऊढा ११. ३, १५; १२. ५, ३.

परिऽएतवे २०. ६५, ३.

परिऽएति ४. ३८, ५; ६. ८, ३.

परिऽकृत्य ५. १४, ३.

परिऽकृत्यमानः ४. १६, ७.

परिऽक्रम्य १२. ४, १७.

परिऽक्रामन् ८. ६, ८.

परिऽक्रोशम् २०. ७४, ७.

परिऽक्षवम् १९. ८, ४; ५.

परिऽक्षवात् १०. ३, ६.

परिऽगृहीता ११. ३, १५.

परिऽगृह्णन्ति १२. १, १३.

परिऽचराः १२. १, ९.

परिऽजाः १९. ५६, ६.

परिऽजातः ३. ६, १.

परिऽज्मन् २०. ७०, ५.

परिऽज्मा ७. १५, ४.

परिऽणहि १९. ४८, १.

परिऽतंसयध्यै २०. ३६, ७.

परितःऽइव १०. ७, ३८.

परिऽतत्नुना १. ३४, ५.

परिऽतप्ताः १. ७, ५.

परिऽधयः ९. ६, १०; १३. १, ४६; १९. ६, १५.

परिऽधातवै २. १३, २; १९. २४, ४.

परिऽधानम् ८. २, १६.

परिऽधाय २. २९, ६.

परिऽधिः ४. ९, १; ५. २९, २; ३; ८. २, २५; १२. २, ४४.

परिऽधिम् ८. २, ९; १२. २, २३.

परिऽनीयमानाम् १८. ३, ३.

परिऽनृत्यति ४. ३८, ३.

परिऽनृत्यन्ति ८. ६, १०.

परिनृत्यन्त्योःऽइव १०. ७, ४३.

परिपदाम्ऽइव २०. ६६, ३.

परिऽपन्थिनः १. २७, १; १२. १, ३२; १४. २, ११.
परिऽपन्थिनम् ३. १५, १.
परिऽपानः ८. ५, १; १६; १९. ३४, ७; ३५, ३.
परिऽपानम् २. १७, ७²; ४. ९, २²; ३; ५. ८, ६; ११. १२, १७; १९. ३५, २.
परिऽपानात् ४. २०, ८.
परिऽपानाय ४. ९, २.
परिऽवेधिरे ६. १३३, ५.
परिऽब्रवीमि १९. ३९, २; ३; ४.
परिऽभुवः ९. १५, १७.
परिभू इति परिऽभू ४. २५, १.
परिऽभूः ३. २१, ४; ४. ३३, ६; ७. ८४, ४; ८५, ३; १३. २, १०; १८. १, ३०.
परिऽममृशुः २०. १३९, ३.
परिऽमर्धिषत् २०. ११८, २.
परिऽमिता ९. १५, २७.
परिऽमिताम् ९. ३, १.
परिऽयन्तः ४. ३५, ४.
परिऽयन्ति १. १, १.
परिऽयान्तम् १३. २, ४; ५.
परिऽयासि १३. २, ६.
परिऽरथ्यम् ८. ८, २२.
परिऽरापिणः १२. ४, ५१.
परिऽरापिणम् ५. ७, २.
परिऽरुजन् १६. १, २.
परिऽवत्सरः ८. ८, २३.
परिऽवत्सराय ६. ५५, ३.
परिऽवत्सरीणम् ३. १०, ५.
परिऽवर्ग्यः ९. २, १४.
परिऽवर्तमाने ९. १४, ११.
परिऽवादम् १९. ८, ४.
परिऽवित्तः ६. ११२, ३.
परिऽविष्टम् ६. १२२, ३; १२. ३, ७; २०. १६, ६.
परिऽविष्य ९. ११, ५.
परिऽवीतः ९. १५, १०.
परिऽवृक्ता ७. ११८, २.
परिऽवृजम् २०. ६६, ३.
परिऽवृतः १७. १, २८.
परिऽवृता १०. ८, ३१; १२. ५, २.
परिऽवेशसः २. ३२, ५; ५. २३, १२.
परिऽवेषात् ९. ६, १२.
परिऽवेष्टारः ९. ११, ३.
परिऽशासम् ५. १४, ३.
परिऽशुम्भन्ति १३. १, ५१.
परिष्कृता ९. ३, १०; १४. १, ७.
परिष्टौ २०. ३७, ७.
परिऽसदम् १८. ३, २२.
परिऽसर्पति ५. २३, ३².
परिऽसर्पन्ति ८. ६, २४.
परिऽसस्वजानाः १. २, ३; ४. ८, ७.
परिऽसस्वजे ६. ८, १.
परिऽसिक्तम् ७. ६०, २.
परिऽसिच्यते १०. ८, २९.
परिऽसीदन्ति ६. ७६, १.
परिऽसूतम् ११. ७, २३.
परिऽसूताः २०. २१, ८.
परिऽसृष्टम् ८. ६, २०.
परिऽस्कन्दाः १५. ३, १०.
परिऽस्कन्दौ १५. २, ६; १४; २०; २६.
परिऽस्तरणम् ९. ६, २.
परिऽस्था ११. २, २५.
परिऽस्रुतः ३. १२, ७.
परिऽस्वजीयसी १०. ८, १९.

परिऽस्वजे १४. १, ४६.
परिऽस्वञ्जल्यस्य ९. ३, ५.
परिऽहवम् १९. ८, ४.
परिऽहस्त ६. ८१, २.
परिऽहस्तः ६. ८१, १.
परिऽहस्तम् ६. ८१, ३.
परिऽहिता १२. ५, ३.
परिऽहिनोमि ८. ४, ६.
परिऽहुता १२. ९, २.
परीणसः २०. ६७, १.
परीत्तः ६. ९२, २.
परुः ४. १२, २; ३; ७.
परुःऽपरुः १. १२, ३; ४. ९, ४; ९. ३, १०.
परुःऽस्रंसम् ६. १४, १.
परुऽशः ९. ५, ४.
परुषऽआह्वः ८. ८, ४.
परुषः ५. २२, ३.
परुषस्य १०. ४, २.
परुषा ४. १२, २; ३; ७.
परुषान् ८. ८, ४.
परुष्णी ६. १२, ३.
परूंषि ९. ३, ३; ६, १; १३, १८; १०. १, ८; २०.
परे ५. २, ६; २४, १५; ९. १४, १२; १३. १, ४०; २०. ३४, ८; १०७, ९.
परे १. १७, २.
परेण ४. ३, २[3]; ५. ११, ५; ९. १४, १७; १८[2]; १०. १, १६; १३. १, ४१; १९. ४७, ७[2].
परेभिः १२. २, २९.
परेयिऽवांसम् १८. १, ४९.
परेषाम् ३. १, १; २, १; ६; ५. ३, २; २०, ३.
परेषु ६. ३६, ३.
परैः १८. ३, ४८.
पर्जन्य ४. १५, ४; ६.
पर्जन्यः ३. २१, १०; ४. ११, ४; ६. ४, १; ८. ७, २१; १०. १०, ७; १२. १, १२; १९. १०, १०; ३०, ५; २०. १३८, १.
पर्जन्यऽजिन्विताम् ४. १५, १३.
पर्जन्यऽपत्नी १०. १०, ६.
पर्जन्यऽपत्न्यै १२. १, ४२.
पर्जन्यम् १. २, १; ३, १; १०. २, १९; ११. ८, ६.
पर्जन्यस्य ३. ३१, ११.
पर्जन्ये ६. ३८, ३.
पर्ण ३. ५, ६; ७.
पर्णः ३. ५, ४; ८; १८. ४, ५३.
पर्णऽधेः ४. ६, ५.
पर्णम् ८. ७, १२.
पर्णऽमणिः ३. ५, १; ५.
पर्णऽमणे ३. ५, २.
पर्णम्ऽइव ५. २९, १.
पर्णयम् २०. २१, ८.
पर्णा २०. १६, १०.
पर्णात् ५. ५, ५; १०. १, २९.
पर्यस्तऽअक्षाः ८. ६, १६.
पर्यायिकेभ्यः १९. २२, ७.
पर्व १. १२, २; २०. ३५, १२.
पर्वणः २०. १६, ९.
पर्वणिऽपर्वणि २. ३३, ७; २०. ९६, २३.
पर्वतः १. १४, १; ४. ६, ८.
पर्वतःऽइव ६. ८७, २.
पर्वतम् २०. १५, ६.
पर्वतस्य ४. ९, १; १२. २, ४१; २०. १६, ७.
पर्वताः ३. २१, १०; ६. १२, ३; ७७, १;

८८, १; ७. १०१, १; ९. १२, १२; १२. १, ११; १७. १, ३०; १९. १०, ८; २०. ३४, १४.
पर्वतात् २. ३, १; ५. २५, १.
पर्वतान् १. १२, ३; ६. १७, ३; १०. २, १८; ११. ८, १०; १३. १, ४७; ५३; २०. ३४, २.
पर्वतानाम् २. ५, ५; ४. ९, ८; ५. २४, ६.
पर्वताय १९. ४८, ३.
पर्वतासः २०. १०६, २.
पर्वतीयम् १९. ४५, ३.
पर्वतीयाः १९. ४४, ६.
पर्वते २. ५, ६; २०. १५, २.
पर्वतेन ८. ४, १९; १२. २, २३; २०. ३६, ६.
पर्वतेभ्यः ३. ३, ३; ६. ५२, १; ८. ४, ४; २०. १६, ३.
पर्वतेषु २. ३१, ५; ४. ३६, ५; ८. ७, १७; ९. १, १८; २०. ३४, ११; ४१, २.
पर्वतेऽस्थाम् २०. ३६, २.
पर्वन् १२. ३, ३१.
पर्वऽशः २०. १५, ६.
पर्वऽसु २. ९, १; ६. १४, १.
पर्वा १२. ९, ४.
पर्वाणि १. ११, १; ८. ३, ४; ११. १०, १२; १२. ११, १०.
पर्शवः ९. १२, ६; १०. ९, २०; ११. ३, १२.
पर्शाने ८. ४, ५; २०. ४३, २.
पर्शुः २०. १२६, २३.
पर्शुम् १२. ३, ३१.
पर्ष ४. ३३, ८.
पर्षणिम् २०. ७२, १.
पर्षत् ६. ३४, १; २; ३; ४; ५; ७. ६५, १.
पर्षि २०. १२, २.
पलदान् ९. ३, १७.
पलदानाम् ९. ३, ५.
पलालऽअनुपलालौ ८. ६, २.
पलाल्या २. ८, ३.
पलावान् १२. ३, १९.
पलितः ९. १५, ९.
पलितम् १. २३, १; २.
पलितस्य ९. १४, १.
पलीजकम् ८. ६, २.
पल्पूलनम् १२. ४, ९.
पवताम् ५. ३, ३; ८. १, ५.
पवते ४. २४, ४.
पवते १०. ७, २; ४; १३. ३, १९; १८. २, १; ६; १४; ३, ५४; ४, ५८; १९. ५४, २; २०. १३७, ५; ६.
पवनेन ४. ३४, २.
पवनैः १८. ३, ११.
पवन्ताम् ७. ८७, १.
पवन्ते १३. ३, २.
पवन्ते १२. ३, २५.
पवमानः ३. ३१, २; ४. ११, ४; ६. १९, १; २; ९. १२, ८; १०. २, २६; ८, ४०; ९, २६; १५. २, ७; १४; २०; २७; १५, ६; १८, ३; १९. ६१, १.
पवमाने १७. १, १३.
पवस्तैः ४. ७, ६.
पवस्व १२. १, १२.
पविता ६. ११९, ३.
पवित्रम् ९. ६, १६; १९. ३३, ३.
पवित्रऽवन्तः २०. १३७, ४.
पवित्रस्य २०. ५२, १; ५७, १४.

पवित्रा ६. १२४, ३.
पवित्रेण ६. १९, ३; ५१, १; १२. १, ३०.
पवित्रेणऽइव ६. ११५, ३.
पवित्रैः १२. ३, ३; १४; २५.
पविऽनसात् ८. ६, २१.
पविम् ७. ८९, ३.
पवीरऽवत् ३. १७, ३.
पशवः २. २६, १; २; ३; ३४, ४; ३. १०, ६; ३१, ३; ७. ४१, १; ६८, १; ९. १, २०; २, ५; १६; १२, २६; १०. ६, ३३; १०, २९; ११. २, ९; २४; ६, ५; ७, २१; ८, ८; १२. १, ४९; ३, १६; ५१; ६, ४; १४. २, २५; १५. २, १०; ६, १४; १५, ८; १६. ४, ७; ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०.
पशव्यम् २०. ८७, ६.
पशुः १. १५, २; ८. २, २५; ९. ६, ६.
पशुना ८. ३, १५.
पशुऽपतिः २. ३४, १; ११. २, २८; ८, ९; १५. ५, ७.
पशुऽपतिम् १५. ५, ६.
पशुपती इति पशुऽपती ११. २, १.
पशुऽपते ११. २, २; ५; ९; ११; १९; २४.
पशुऽवन्धाः ११. ९, १९.
पशुऽभिः ४. ३६, ५; ७. ८६, ४; ५; ९. ३, १४; १०. १, १०; ११. १, २२; १२. ४, २; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २१; २४.
पशुऽभ्यः ४. ११, २; १४. २, १८; १५. २, ११.

पशुम् ८. ७, ११; १८. ३, १८; १९. ६, १५; ७१, १; २०. २५, ४.
पशुऽवित् ११. १, १५.
पशुषु १. ३०, ३; २. ३१, ५; १०. ३, १६; १४. २, ६२; १९. ३, २; ४८, ५.
पशून् ३. २८, १; २; ४; ५; ६; ९. ८, ४; १०. ३, १२; ६, ३५; ११. १, १७; १५. ५, ३; १६; १४, ११; १९. ६, १४; ४८, ५; ६३, १.
पशूनाम् १९. ३१, १.
पशूनाम् २. २८, ३; ३४, १; ४. २२, ४; ५. २४, १२; २८, ३; ३१, ३; ९. ४, ६; १०, ३; ५; ७; १०; ११. २, २८; १२. २, ५३; ३, २१; ४, २१; ४०; १३. १, ३८; १५. २, १२; ६, १५; १७. १, ४; १९. ३१, २; ५[२]; ६.
पशोः १९. ३१, ८.
पश्चा १०. ४, ११; ८, ७; ११. ६, २२; २०. ९१, ११.
पश्चात् ४. ४०, ३; ६. ४०, ३; ७. ५३, १; ८५, १; ८. ३, १९; २०; ५, १७; ६, १५; ९, ९; १०. ८, १०; ९, ८; ११. २, १३; ८, १८; १२. १, ३१; ३२; १३. २, २७; ३, ११; २५; ४, ७; १८. ४, ९; ११; १९. ६, ९; १५, ३; ५; १६, १; २७, १४; ४८, ४; २०. १७, ११; २०, ६; ५७, ९; ८९, ११; ९४, ११; १०७, १५.
पश्य १३. ८, ३; ५; ६; ९, १; २; ४.
पश्य ८. ३, १०; ९. १५, ९; १०. ८, ३२; १४. १, २८; १८. ४, ३.
पश्यत् ९. १४, १५.
पश्यत् २. १, १.
पश्यत १४. २, २८.

पश्यत १. ३३, ४; ७. २७, ६; ७५, १; १३. ८, ३[२]; ५[२]; ६[२]; ९, १[२]; २[२]; ४[२]; १६. १, १२; १८. ४, ३७.

पश्यतः १९. ६२, १.

पश्यति ४. २०, १; ६. ३४, ४; ७६, २; ११. ९, २३.

पश्यति ४. ५, २; १६, १; २०, १[४]; ९. १०, ८; १०. ८, १९; ३२; १३. १, ४५; ४, ११; ५, ६; १९. ५३, ६.

पश्यते ९. ४, १९.

पश्यन् १२. २, ७; १३. २, २२; १४. १, ५७; २०. ४७, १९.

पश्यन्ति ८. ९, ९; ९. १, ३; १०. ८, १४.

पश्यन्ति ४. १६, ४; ७. २७, ७; ८. ९, ९; १३. १, ३९; २, ४; २०. २५, २.

पश्यसि ८. ३, ५; २१; १३. २, २१; २०. ४७, १८; ८७, ६.

पश्यसि ११. २, २५; १३. १, ३९; १८. २, ५०.

पश्याः ४. २०, ५.

पश्यानि ४. २०, २.

पश्याम १. ७, ५; १३. २, ३६.

पश्यामः १९. ५३, ३.

पश्यामि ८. ७, १८; १७. १, ७.

पश्यामि ३. १३, ६; ४. २०, ४; ८; १८. २, ३२.

पश्यासि १०. ३, ६.

पश्यासि १८. १, ५४.

पश्यासै ३. ४, ३.

पश्येम ७. ५, ३; १९. ६७, १.

पश्येम ६. ६२, ३; १२०, ३.

पश्वः ७. १५, ३; १८. ३, २३.

पसः ४. ४, ६; ७; ६. ७२, २[३]; ३; १०१, २; ३.

पस्त्यम् २०. ३२, १.

पस्त्यानाम् ९. १५, ८.

पस्त्योः २०. ३१, ५.

पस्पशे ७. २७, ६.

पस्पृधाते इति ८. ४, १२.

पस्पृधानम् २०. ३५, १५.

पांसुः १२. १, २६.

पांसुरे ७. २७, ४.

पांसून् ७. ११४, २.

पाकः ९. १४, ६.

पाकम् ९. १४, २२; १०. १, १८.

पाकऽशंसम् ८. ४, ९.

पाकऽसुत्वनः २०. १२६, १९.

पाकस्य ४. १९, ३.

पाकेन ८. ४, ८.

पाङ्क्तम् १२. ३, १०.

पाजः ४. ३१, ३; २०. १२३, २.

पाजस्यम् ४. १४, ८; ९. १२, ५.

पाजस्यात् १०. १०, २०.

पार्श्वऽजन्यस्य ४. २३, १.

पाटाम् २. २७, ४.

पाणिना १२. १०, २.

पाणिऽभ्याम् २. ३३, ६; २०. ९६, २२.

पात् १९. ६, २.

पात ३. १६, ७; १२. २, ४७; १९. ११, ५; २०. १२, ६; १७, १२; ३७, ११; ८७, ७.

पातन ६. ३, १.

पातम् ६. ३, १; ७. ७७, ५.

पातम् २. १६, १; २.

पातय १. ८, ३; १९, १; २३, २; ६. १३४, ३; ११. २, २६; १९. २८, ४; ५०, ४.

पातयाथ ४. १५, ५.

पातयामसि ४. ७, ४.

पातयासि १२. ३, ५३.

पातवे १२. १, ३८; २०. ९२, ७.

पाताम् ६. ३, २; ३.

पाति ९. १५, २३.

पातु ६. ३, १; २[४].

पातु २. ४, २; ३; २८, १; ४. १०, १; ३; ५; ५. २८, ५; ९[३]; ६. ४, १; ४५, ३; ४७, १; ५३, १; ७. ५३, १; ८. २, २६; ३, १; ४, २३[२]; ५, ४; ६, २१; १०. ३, १०; १६. ४, ४; १७. १, ३०; १८. १, १९; २, ५५[२]; ३, २५; २६; २७; २८; ४९; १९. १७, १; २; ३; ४; ५; ७; ८; ९; १०; २०, १; ३; २७, १[४]; २[२]; ३२, १०; ३३, १; ३४, ५; ३५, ४; ४५, ५; २०. १७, ११; ८९, ११; ९४, ११.

पातॄन् ३. १२, ८.

पात्रम् ८. १३, २; ६; १०; १४; १४, २; ६; १०; १४; ११. ३, ९; १२. १, ६०; ३, ८; ३७; ४८.

पात्रऽहस्ताः ९. ११, ३.

पात्राऽइव ८. ४, २१.

पात्राणि ६. १४२, १; ९. ६, १७; २०. ९४, ५.

पात्रान् १०. १०, ९.

पात्रे ४. १७, ४; ५. ३१, १; १२. ३, २५; ३३; ३६; ४०.

पात्रेषु १०. १०, ११; १२.

पात्रैः १२. ३, ३०.

पाथ २०. १, २.

पार्थः २. ३४, २; ५. १२, १०.

पाथः ७. ३०, १.

पादः १९. ६, ३.

पादम् ४. १८, ६; ५. ३१, ११; ११. ६, २१.

पादय १०. १, १७.

पादय ८. ६, १६; ९. २, १; १०; १३. १, ३१.

पादयन्तम् ११. २, १८.

पादयस्व ६. ८८, ३.

पादयाति १०. ३, ३.

पादयाथः ९. २, ९.

पादयामि १०. ५, ३६; ११. १, १२; २१; १६. ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३.

पादयोः १९. ६०, २.

पादऽवत् ११. १०, ११.

पादान् १४. १, ६०.

पादाभ्याम् ९. १३, २१; १०. ७, ३९; ११. ४, १५[२].

पादि ७. ७३, २; ८. ६, २०.

पादौ ६. ९, १; १०. १, २१; ११. १०, १४; १५. ३, ४; १९. ६, ५; ४९, १०.

पादौ १. २७, ४.

पानै ५. २९, ८.

पान्तु ६. ३, १; ४, २.

पान्तु ५. ३, ९; ७. ६६, १; १०. ५, २२; १९. १७, ६.

पाप १९. ८, ५.

पापः ५. १८, २; १९. ५७, ३.

पापऽकृते १०. १, २३.

पापऽकृत्यया॑ ३. ३१, २.
पापऽकृत्वा॑नम् १९. ३९, ३.
पापऽत्वाय॑ २०. ८२, १.
पापम् २. १२, ५; ४. ३६, ८; १०. १, १०; ३, ६; १२. २, ५०; १०, २; १८. १, १४; १९. ९, १४.
पापया॑ ५. १७, १८; ७. ५८, ६; ६७, २; १४. १, २७; २०. ७४, ५.
पापऽलोकान् १२. ११, ३.
पापऽवादात् १०. ३, ६.
पापात् ७. १०५. १; १०. १, ११; ३, ४.
पापाय॑ १३. ७, १४.
पापि ७. १२०, १.
पापिष्ठाः ७. १२०, ३.
पापीः ७. १२०, ४; ९. २, २५.
पाप्मन् ६. २६, १²; २; ११३, २.
पाप्मना॑ ३. ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १०. ७, ४०.
पाप्मने॑ ५. १४, ६.
पाप्मा ५. २२, १२; ६. २६, २; १२. ८, ३; १७. १, २९; १९. ३२, ९; ३६, २.
पाप्मानः ११. १०, १९.
पाप्मानम् ४. १८, ३; ८. १४, १२; १२. ३, १८.
पाययामसि ८. ७, २२.
पायवः ६. ३, २.
पायुऽभिः १९. ४७, ५.
पारम् ३. ११, ३; ६. १२३, १; १९. ४७, २³; २०. ७६, ५; ९६, ८.
पारय ४. ३३, ७; १७. १, २५; २६; १९. ५०, २.
पारयन्तु ५. २८, २.
पारयात् ४. १७, २.
पारयाति ११. १, ५; २०. ४६, २.
पारया॑मसि ८. ७, ७; १९.
पारयामसि ८. १, १८.
पारया॑मि ८. २, ९.
पारयिष्णु ५. २८, १४; ८. २, २८.
पारयिष्णुः ६. ९२, २.
पारयिष्णू इति॑ १९. १३, १.
पारस्वतम् ६. ७२, ३.
पारिषत् २०. ३१, ३.
पारुषेयः ५. २२, ३.
पारुष्यम् १२. ८, ३.
पारे १. २७, १; ६. ३४, ५.
पार्थिवः १४. १, ३; ५; २०. १२१, २.
पार्थिवम् ४. १, ४; १९. ४७, १.
पार्थिवस्य २. २९, १; २०. १७, १२; ३६, ९; ८७, ७.
पार्थिवाः ९. ५, १४; १०. ९, ६; ११. ७, २१; ८, ८; १९. ९, ७; ११, २.
पार्थिवात् ८. ४, २३; २०. ७०, ६.
पार्थिवानाम् २. २८, ३.
पार्थिवानि ४. २५, २; ७. २७, १; २०. ३६, ८.
पार्थिवासः ७. ५१, १; १९. ११, ४.
पार्थिवे १८. १, ४६.
पार्थिवेभ्यः १६. ४, ४.
पार्श्वम् ४. १४, ७; ८; १२. १, ३४.
पार्श्वाभ्या॑म् २. ३३, ३; २०. ९६, १९.
पार्श्वे इति॑ ९. ४, १२; ५, २०; १३, १५; ११. १०, १४.
पार्ष्टेयम् २. ३१, ४.
पार्ष्णिऽभ्याम् २. ३३, ५; २०. ९६, २१.
पार्ष्णी इति॑ १०. २, १.
पार्ष्णीः ८. ६, १५.

पार्ष्ण्यां ६. ४२, ३; ८. ६, १७.
पार्ष्ण्योः ६. २४, २.
पालित्यम् ११. १०, १९.
पावक १३. २, २१; १८. ४, ५९; २०. ४७, १८.
पावकः ६. ४७, १; ८. ३, २६.
पावकऽवर्णाः २०. १०४, १.
पावकाः १. ३३, १; ४; ६. ६२, ३; १२. २, ११; २८.
पावमानम् ११. ९, ६.
पावमानी १९. ७१, १.
पाशः ९. ३, २.
पाशम् २. ८, १; ३. ७, ४; ७. ८८, ३; ९. ३, २४; १८. ४, ६९.
पाशाः ४. १६, ६; १४. २, ४९.
पाशात् २. १०, १; २; ३; ४; ५; ६²; ७; ८; ४. ३६, १०; १४. १, १९; ५८; १६. ८, ३; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३२.
पाशान् ६. ११२, १; २²; ११७, १; ११९, २; १२१, १; ७. ८२, २; ३; ८८, ४; ९. ३, १३; १४; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; १४. १, ५६; ५७; १६. ६, १०; १८. ४, ७०.
पाशिनः ५. ६, ३; ७. १२२, १; १७. १, ८.
पाशे २. १२, २.
पाशेभ्यः १. ३१, २; ८. १, ३; १९. ४४, ४.
पाशेषु १२. ४, ३७.
पाशैः ३. ६, ५; ४. १६, ७; ९; ६. ११२, ३; १९. ६६, १.
पास्त १२. ३, ४३.
पाहि ४. ३२, २; २०. ६, ६.
पाहि २. ७, ३; ४; १६, ३; ४; ५; ३५, ४; ४. ९, ६; १०; १९, ८; ५. ३, २; ६. ४६, २; ११०, २; ११२, १; ७. ८९, १; १११, १; ८. ३, २०; ६, २२; १६. ५, ३; ४; ५; ६; ७; १०; १७. १, ९; १८. १, ३४; ४, ९; १९. ४४, ६; ४७, ५; ४८, ३; ४; ५५, ५; ५६, ६; ६६, १; २०. १, १; ६, १; ८, १; २०, १; ५७, ४; ८७, २; ९६, १; २.
पिंश १९. २८, ९⁴.
पिंशतु ५. २५, ५.
पिङ्ग ८. ६, २५.
पिङ्गः ८. ६, ६; १८; १९; २१; २४.
पिङ्गलः ११. ७, २६.
पिङ्गा २०. ९२, ६.
पिण्ड्ढ १९. २९, ६⁴.
पितः ६. ४, ३.
पितरः २. १२, ५; ६. १२३, ३²; १८. ३, १६.
पितरः १. ३०, २; ३. २७, २; ५. २४, १५; ६. ११६, ३; ८. १२, ३; १३, ५; ८; ९. २, १९; १०. ६, ३२; ९, ९; १०, २६; ११. १, १९; ७, २; ९, २७; १२. ३, ३४; १४. २, ७३; १८. १, ४२; ४४²; ४७; ५०; ५४; ५५; ५८; २, २६; २९; ४८; ४९; ३, १०; २१; ४५; ४६; ५२; ५९; ७२; ४, ३६; ४०; ४४; ४६; ५१; ५२; ६४; ६८; ८६²; ८७; १९. ११, १; ५६, ४; २०. १६, ११; ३६, २.

पितरः ४. १५, १५; ७. १३, १; ९. ५, ११; १२. २, ३३; १८. १, ५१; ५२; ३, १४; १९; ४३; ४४; ४, ६२; ६३; ८१^{२}; ८२^{२}; ८३^{२}; ८४^{२}; ८५^{२}.

पितरम् १. २, १; ३, १; २; ३; ४; ५; ४. १, ७; ३०, ७; ५. १, ८; ११, ११; १४, १०; ६. ३१, १; ११०, ३; १२०, १; १४०, १; २; ३; ७. १, २; २, १; ८. ९, ७; ९. ५, ३०; १४, ८; १२; १८; २१; १०. १, २५; ११. २, २९; १४. १, १५; १८. ४, ३५; २०. ४८, ४.

पितरा १८. १, २३; ३१.

पितरौ ६. १२०, ३; २०. १२५, ५.

पितरौ १४. २, ३७.

पिता १. २४, ३; २. १, २; ३; ९, २; २८, ४; ३. ९, १; २३, ६; ४. ५, ६; ९, ८; १५, १२; १९, ५; ५. ४, ९; ५, १; ८; १३, ७; २४, १२; ३०, ५; ६. १६, २; ४६, १; ११६, २; १२०, २; १३१, ३; ७. ६, १; ८. ७, २; ९. ४, २; ४^{२}; १४, १५; १५, १२^{२}; १०. ३, ८; ८, २८; ११. ६, १०; २०; ९, १५; १६; १०, १८; १२. १, १२; ३, ५; १३. ३, १९; १४. २, ३७; १५. ६, २५; ७, २; १८. १, ५९; ३, ६७; ४, ५६; १९. ३९, ३; ५३, ४; ८; २०. २६, ३; ७९, १; ८२, २; ९०, १; ९१, १; १०८, २.

पिताऽइव २. १३, १; ८. ६, ७; १०. ६, ५; १२. ३, १२; २०. ८, २; ७३, ६; ११४, २.

पितापुत्रौ ६. ११२, २.

पितामहः ५. ५, १; ११. ९, १६; १५. ६, २५; ७, २.

पितामहम् ९. ५, ३०.

पितामहस्य १५. ६, २६.

पितामहाः ११. १, १९; १८. २, ४९; ३, ४६; ५९.

पितामहान् १८. ४, ३५.

पितुः १. १४, २; २. १, २; ३. २५, ५; ३०, २; ४. ६, ३; ६. ११६, ३; ७. २, १; ९. १४, १५; १५. ६, २६; १८. १, १; २, ४९; ३, ४६; ५९; ४, ५६; १९. ४७, १; २०. ११५, १; १४२, ६.

पितुम् २०. ३५, ७.

पितृऽकृतात् ५. ३०, ४.

पितृऽबन्धु १२. ९, ५.

पितृऽभिः ६. ६३, ३; ७१, २; ८४, ४; १२. ३, ८; १८. १, ४३; ६०; २, २१; ३, ८; ५८; ४, ४७.

पितृऽभ्यः ५. ३०, १२; ७. १५, ४; ८. १२, ४; १०. १, ११; १२. २, ३२; ३४; ४, ३२; १४. १, ४६; २, २०; १८. १, ४६; २, ५; १०; २७; ४९; ५४; ३, ४२; ४, ३९; ५०; ५१; ६५; ७३; ७८; ७९; ८०.

पितृऽमते १८. ४, ७२; ७४.

पितृऽयज्ञाय १२. २, ७.

पितृऽयानम् ५. १८, १३; ८. १२, ४; १५. १२, ५; ९.

पितृऽयानाः ६. ११७, ३.

पितृऽयानैः १२. २, १०; १८. ४, १; ६२.

पितृऽलोकम् १८. ४, ६४.

पितृऽलोकात् १४. २, ५२.

पितृषु १. १४, १; ३; ५. १९, ५; ७. ४२, २; ११. १, २८; ३१; १२. २, १०; १८.

२, २५; २८; ५२; ४, ४८; ४९; १९. ३, ३.
पितृऽसदनाः १८. ४, ६७.
पितृऽसदने १८. ४, ६७.
पितृऽसदम् १४. २, ३३.
पितॄणाम् २. १२, ४; ३. २९, ४; ५. २४, १४; ६. ४४, ३; ७. ७०, २; १०. ५, १३; ११. १, ५; १२. २, ९; ४५; १८. ३, ६३; ७३.
पितॄन् ५. ३०, १; ८. १, ७; ८, १५; १२, ३; १३, ५; ९. १४, १०; ११. ८, ११; १६; ११, २४; १४. २, ६९; १५. १४, १३; १८. १, ४५; ५६; ५७; २, ४; ११; २३; ३४; ४६; ४, ४०; ४१.
पित्तम् १. २४, १; १८. ३, ५.
पित्रे १. ३१, ४; ५. ११, १; ७. १५, ३; ५९, २; २०. ८८, ६; ९२, १२.
पित्र्यम् ६. १२२, २.
पित्र्या ४. १, २.
पित्र्यात् ६. १२०, २; १०. १, १२.
पित्वः ८. ४, १०; १८. १, ४५.
पिनष्टन ८. ४, १८.
पिनष्मि २. ३१, १; ३२, ३; ५. २३, १०.
पिनाकम्ऽइव १. २७, २.
पिन्वत ६. २२, २.
पिन्वतम् ६. ९७, २.
पिन्वतीम्ऽपिन्वतीम् ९. ५, ३४.
पिन्वते २०. ७१, ३.
पिन्वते २०. ९१, ४.
पिन्वन् ९. ५, ३४.
पिन्वन्तम् ९. ५, ३४.
पिन्वमानः ४. ३४, ८; १८. ४, ३५.
पिन्वमाना ३. १७, ९.
पिन्वमानाः ४. ३४, ५; ६; ७.
पिन्विरे २०. ९१, २.
पिपतिषति १२. २, ५२.
पिपर्ति ९. १५, २३; १३. ३, ४.
पिपर्ति ९. १, ५; २०; ११. ७, १; २; ४.
पिपर्तु ५. २८, ५; ६. ५३, १; १२. १, १२.
पिपर्मि १. ३५, ४.
पिपानः ९. ४, २१.
पिपीलः १८. ३, ५५.
पिपीलिकाः ७. ५८, ७.
पिपृग्धि १८. १, १२.
पिपृत ५. २६, ५.
पिपृहि ७. ३६, १.
पिपृहि ७. २१, ४; ८४, १.
पिपेश १४. १, ६०.
पिपेष २०. ११, ६.
पिप्पलम् ९. १४, २०; २१.
पिप्पली ६. १०९, १.
पिप्पल्यः ६. १०९, २.
पिप्युः २०. १२, ४.
पिप्युषी २०. २७, ३.
पिप्रतः २०. १३८, २.
पिप्रायस्व ६. ११०, १.
पिब २. ५, १; ७. ७६, १; ७७, ११; ९. १५, २०; २०. ३, १; ४, १; ५, ५; ६, २; ७, ४; ३२, २; ३३, १; ३८, १; ४७, ७; ६७, ५; ७; ११७, १.
पिब ५. २५, ६; ७. २७, ३; ८१, २; १९. ४५, ५; २०. ८, २; २२, ३; २४, ७; ५७, २; ६७, ६; ६८, २.
पिबत २०. ६७, ४.
पिबतम् ७. ६०, १; ७७, ४; २०. १३, १.
पिबताम् २. २९, ६.

पिबति ५. ५, २.
पिबति ५. १८, ४.
पिबतु १३. १, २७; २०. २, १; २; ३; ४.
पिबध्यै २०. ८, ३; १४३, ९.
पिबन्तम् २०. ५३, १; ५७, ११.
पिबन्ति १. ४, ३.
पिबन्ति २०. १०९, १.
पिबन्तीः ४. २१, ७; ७. ७९, १.
पिबसि ८. २, १९.
पिबात् ७. १५, ४.
पिबाथः २०. १४३, ४.
पिबामः ६. १३५, २.
पिबामि ६. १३५, २; २०. १२६, १९.
पिबामि ६. १३५, २.
पिबाव ४. ३२, ७.
पिब्दना २०. ८०, २.
पियारुः १९. ५७, ५.
पियारुम् १९. ५७, ४.
पियारूणाम् ११. २, २१.
पिशङ्गम् १४. २, ४८.
पिशङ्गऽरूपः ९. ४, २२.
पिशङ्गऽरूपम् २०. ५२, ३; ५७, १६.
पिशङ्गऽसंदृशम् ६. ३३, ३.
पिशङ्गे ३. ९, ३.
पिशाचः ५. २९, ४; ६; १२. ३, ४३.
पिशाचऽक्षयणम् २. १८, ४.
पिशाचऽचातनम् २. १८, ४.
पिशाचऽजम्भनीः ५. २९, १४.
पिशाचम् ४. २०, ७; ९; ५. २९, १०.
पिशाचाः १. ३५, २; ४. ३६, ७; ८; ५. २९, ६; ७; ८; ९; ६. ३२, २.
पिशाचान् ४. २०, ६; ३६, ४; ३७, १०; ८. २, १२; १२. १, ५०; ३, १५.
पिशाचानाम् ४. ३६, ६.
पिशाचैः ४. ३६, ७; ५. २९, ५.
पिशाच्याः १. १६, ३.
पिशितम् ५. १९, ५; ६. १२७, १.
पिशिता १२. ८, ९.
पिशुनेभ्यः ८. ४, २०.
पिश्यमाना १२. ८, ९.
पिष्टाः १२. २, ५३.
पींषस्व १९. ४९, ४.
पीडय १२. ११, ९.
पीतये १. ६, १; ७. ६०, १; २०. २२, १; २४, ४; ८; ९; ५४, २; ६९, ४; ७६, ६.
पीतिम् २०. २५, ७; ३३, २; ८७, २.
पीत्वा २. १३, १; १०. १०, ३१; २०. २१, ४; ६८, ८; ९२, ४; ९४, ८.
पीत्वी २०. ६, ७; ४२, ३.
पीपरत् १९. ४०, ४.
पीपिहि २०. ८, १.
पीवः ९. १२, १८.
पीवःऽपाकम् ४. ७, ३.
पीवरीम् ३. १७, ३.
पीयकान् १६. ६, ८.
पीयतः ५. १८, १५; २०. १६, ६.
पीयते ५. १९, ५.
पीयन्ति २०. ११४, २.
पीयूषः ९. ४, ४.
पीयूषम् ८. ३, १७; ९, २४.
पीला ४. ३७, ३.
पीलुऽमती १८. २, ४८.
पीवः २०. १२६, १४.
पीवसा १८. २, ५८.
पीवसि १. ११, ४.
पुंश्चली १५. २, ५; १३; १९; २५.

पुंसः ३. ६, १; ६. ७०, १; २; ३; ९. १४, १५; १२. ३, १.
पुंसाम् ४. ४, ४; ७. १४, १.
पुंसि ६. ११, २.
पुंसे ५. ३०, ३.
पुच्छऽधौ ७. ५८, ८.
पुच्छम् ९. ४, १३; १२, ८; १०. ९, २२; १२. ७, १०.
पुच्छे ७. ५८, ६.
पुच्छेन ७. ५८, ८.
पुण्डरीकम् १०. ८, ४३.
पुण्डरीकऽवान् ६. १०६, १.
पुण्यऽगः १९. ८, ५.
पुण्यऽगन्धयः ४. ५, ३.
पुण्यऽगन्धिः ८. १४, ८.
पुण्यऽगन्धे ८. १४, ५.
पुण्यऽजनान् ८. ८, १५; ११. ८, १६; ११, २४.
पुण्यम् ८. १४, ७; ८; ९. ५, १६; १९. ७, ३; ४; ८, ५; ५६, ५.
पुण्या १२. ५, ६.
पुण्याः ७. १२०, ४; १५. १३, २; ४; ६; ८; १०; १९. ५४, ५.
पुण्यान् १९. ५४, ५.
पुण्यानाम् १५. १३, ८.
पुत्र ४. १६, ९.
पुत्रः १. २५, ३; ३. २३, २; ३०, २; ४. ३९, ९; ५. १, ८; ६. ४६, २; ७. १, २; ६, १; ९. १४, १५; १०. ८, २८; १२. १, १२; ३, ४७; १३. २, ९; ३, २६; १४. १, १५; २, २४; १६. ५, १; ४; ५; ६; ७; ८; १९. ५३, ४; ५४, ३.
पुत्रःऽइव ५. १४, १०.
पुत्रकाः २०. ९२, ५.
पुत्रऽकामा ११. १, १.
पुत्रऽकाम्या ६. ८१, ३.
पुत्रम् १. ११, ५; २८, ४; २. २८, १; ३. १६, २; २३, ३; ४; ५; ५. १, ९; २०, ५; २५, ९; १०; ११; १२; १३; २६, ५; ६. ८१, २; ३; ९. ५, ३०; १०. ५, ४४; ११. ६, २०; ११, ८; १३. २, ३७; १६. ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१; १८. २, ५०; ३, ५०; ४, ३९; २०. १३७, २.
पुत्रम्ऽइव ११. ६, १०; २०. १२५, ५.
पुत्रऽविद्याय ३. २३, ६.
पुत्रस्य ६. ११, १; २; १०. ५, ३६; १२. २, २५; २०. १०४, ४.
पुत्राः १. ३०, ३; ३. ४, ३; ९. १४, १३; १२. ३, ३४; ४०.
पुत्राणाम् २. ९, २; ३. २३, ३; ६. १३१, ३; ७. ८, १.
पुत्रात् ६. ११६, ३.
पुत्रान् २. १३, १; ३६, ३; ६. १२०, ३; १२. ३, १२; ४, ३८; १४. २, ४.
पुत्राय १२. १, १०.
पुत्रासः ७. ५९, २; १८. १, २; २०. ९१, २.
पुत्रासः १२. ३, ४.
पुत्रिणीम् १४. १, ६२.
पुत्रिऽयन्ति १४. २, ७२.
पुत्रे १६. ७, ८.
पुत्रेभ्यः ६. ३०, ३; १०. ६, ५; ११. १०, १०; १२. ३, ११; १८. ३, ४३; ६७; २०. ७९, १.

पुत्रैः **६.** ४, १; **१२.** ३, ६; १७; **१४.** १, २२.

पुत्रौ **८.** ७, २०.

पुनः **१.** १, २; २४, ४; **२.** २४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; **३.** १, ६; ६, ७; ९, १; १०, ७; ११, ६; **४.** १२, २; १३, १[२]; **५.** ८, ७; ११, ८; १४, ४; ५; ७; ८; १०; १२; १३; १७, २; १०[३]; २२, ४; ११; २९, ५; ३०, ७; ३१, १; २; ३; ४; ५; ६; ७; ८; ९; **६.** ५३, २[४]; ६३, २; ७५, २; ३; ७७, ३; ७८, १; ८४, ३; १०९, ३; १११, ४[४]; १३१, ३; १३९, ५; **७.** ५, २; १०, ४; ५५, ३[२]; ६८, १; ६९, १[३]; **८.** १, २०; २, १; ४, ३; **९.** २, १२; **१०.** १, २४; ३०; ४, ४; **११.** १, १३; २५; ६, १४; २०; **१२.** २, ५; ६[३]; १०; ५२; ३, २०; ४८; **१३.** २, २५; **१४.** १, ४; २, २; १०; ४७; **१८.** २, १०; १३; २६; ३, ६; ५८; ७०; ४, ६३; ६४; **१९.** ६, २; ८, ३; ४४, १०; ४६, ४; ४९, ७; ५४, १; **२०.** ४०, ३; ६९, १२; ९६, १०; १२६, २१[२].

पुनःऽदाय **५.** १७, ११.

पुनःऽनवः **८.** १, २०; **१०.** ७, ३३; ८, २३; **२०.** ९६, १०.

पुनःऽनवाः **८.** ७, ८.

पुनःऽभुवा **९.** ५, २८.

पुनःऽभुवाः **१.** २७, २.

पुनःऽमघ **५.** ११, १.

पुनःऽमघः **५.** ११, २; **७.** १, २.

पुनःऽमघेषु **५.** ११, ७.

पुनःऽसरः **६.** १२९, ३.

पुनःऽसरम् **१०.** १, ९.

पुनःऽसराम् **४.** १७, २.

पुनर्ते **७.** २८, १.

पुनन्तु **६.** १९, १[३]; **१०.** ६, ३.

पुनन्तु **६.** ५१, २; **१८.** ३, ११.

पुनर्वसू इति पुनःऽवसू **१९.** ७, २.

पुनाति **१२.** २, ११; **१८.** ३, ४०.

पुनातु **६.** १९, १; २; ६२, १; ९६, ३; ११९, ३.

पुनानः **१२.** ३, ५४.

पुनामि **१२.** १, ३०.

पुनीताम् **६.** ६२, १.

पुनीहि **६.** १९, ३; **११.** १, ११; **१९.** ३३, ३.

पुमांसम् **३.** २३, ३; **५.** २५, १०; ११; १२; १३; **६.** ११, ३; **८.** ४, २४; ६, २५; **११.** १, ३४.

पुमान् **१.** ८, १; **३.** ६, १; २३, २; ३; **५.** १४, ६; **७.** १००, ३; **९.** ४, ३; **१०.** ४, ८; ७, ४३[२]; ८, २७; **१२.** ३, १.

पुम्ऽसु **१२.** १, २५.

पुम्ऽसुवनम् **६.** ११, १.

पुरः **१०.** ६, १०; २०; **१२.** १, ४३; **१९.** ५८, ४; **२०.** ७, २; २१, ८; ३७, ५; ५३, १; ५७, ११; ७५, २; ९०, २.

पुरः **१.** २१, १; २७, ४; **४.** ७, ७; २७, २; **५.** ६, २; ३०, १२; **६.** ३१, १; ४०, ३; ५२, १; **७.** १०, २; **८.** ५, १७; ६, १५[२]; **१०.** ८, ७; **११.** ६, २२; **१४.** १, ५९; **१९.** ४, २; ६, ९; १३, ९; १५, ६; ४८, ४; **२०.** ५, ३; २०, ६; ४८, ४; ५७, ९; ८८, १.

पुरःऽएता **३.** १५, १; १६, ५; **५.** २०, १२; **७.** ९, १; **१०.** ३, २.

पुरःऽगवः १२. १, ४०; १४. १, ८.
पुरःऽगवाः १८. ४, ४४.
पुरःऽगवी ४. १३, ७.
पुरःऽगाः ५. १२, ११.
पुरःऽदधिरे ५. ८, ९.
पुरःऽधत्से ५. ७, २.
पुरःऽधायाम् ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
पुरःऽयोधः २०. १८, ६.
पुरःऽरथम् २०. ९५, २.
पुरःऽसरौ १५. २, ८; १४; २०; २८.
पुरःऽहितः ३. १९, १; ४; ७. ६४, १; १०. १, ६; २०. ५८, ४.
पुरःऽहितम् ११. १२, १८.
पुरःऽहिताः ८. ५, ५; ६.
पुरम् ५. २८, ११; ७. ७४, १; ८. ३, २२; १०. २, २८; २९; ३०; ३३; १९. १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २०. २१, ७; ९१, ५; ९२, ५.
पुरम्ऽदरः ८. ८, १.
पुरम्ऽधिः १४. १, ५०; १९. १०, २.
पुरम्ऽध्याम् २०. ६९, १.
पुरस्तात् १. ७, ५; ४. १, १; ११, ४; ४०, १; ५. ६, १; २३, ६; २९, १; ६. ६०, १; ७. ५३, १; ८५, १; ८. ३, १९; २०; १०. ३, २; ८, १०; ११. १, ३२; २, ४; १७; ८, १८; १२. १, १३; ३२; ५५; ३, २४; ३७; १३. ३, ११; १८. २, ५५; ३, ४९; ४, ९; ११; १९. १५, ३; ५; १६, १; २; १७, १; २७, १४; १५; ५६, ६; २०. १७, ११; ८९, ११; ९४, ११.
पुरा ५. ३०, १७; ६. १२, २; ३३, २; ९९, १; ७. २६, २; ७३, १; ९. ६, १२; १०. २, ३०; ३, १६²; ७, ३१²; ११. १, ५; १५; ५, ७; १०, ३; १०; १२. ३, ४६; १३. २, १३; १४. २, ४७; १८. १, ४; २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५; ५७; ३, ३०; ३१; ३२; ३३; ३४; ३५; ४, ५६; १९. ३४, ८; ५४, ३; ५६, २; २०. १४, ३; २१, ७; ३६, ४; ६२, ३; ६७, २; १२६, १०.
पुराणः २०. १७, ५.
पुराणम् १०. ७, २६²; ८, १७; ११. ९, २४; १५. ६, ११; १८. ३, १.
पुराणऽवत् ७. ९५, १; २०. १७, ९.
पुराणऽवित् ११. १०, ७.
पुराणस्यं १५. ६, १२.
पुराणी १०. ८, ३०.
पुराणीः १२. २, ४१.
पुराम् २०. ३५, ५; ६४, ३.
पुरिऽतत् ९. १२, ११; १०. ९, १५.
पुरीकयाः ११. २, २५.
पुरीषिणः ११. १, ३२.
पुरीषिणम् ९. १४, १२.
पुरु ६. ४९, ३; ७. २२, १; १८. १, १; १९. ४९, ४; २०. ५६, ४; ७३, ६; १२०, १.
पुरुः १९. ६१, १.
पुरुऽकृत् ७. ७६, १; २०. ११८, २.
पुरुऽकृत् २०. २१, ३.
पुरुऽक्षु ५. ३, ८; २७, १०.
पुरुऽक्षोः २०. ३६, ३.
पुरुऽचन्द्रैः २०. २१, ५.
पुरुऽजातः १९. १०, २.

पुरुऽतमम् २०. ६८, १२; १४३, १.
पुरुऽत्रा ४. ३०, २; ६. १२६, १; १०. २, ६; ८, १२; २०. ९३, २; ९७, १२.
पुरुऽदंससा २०. १३९, ५.
पुरुऽदमासः ७. ७७, १.
पुरुऽदिनेषु २०. ७६, १.
पुरुऽधा ७. ५, ५; ८७, ५; १८. १, २८.
पुरुऽनामानम् ६. ९९, १.
पुरुऽप्रियम् २०. १०१, २.
पुरुभू इति पुरुऽभू २०. १४३, ४.
पुरुऽभोजसः २०. ५१, २.
पुरुऽभोजसम् २०. ९, २; ११, ९; ४९, ५.
पुरुऽमायः २०. ३६, १.
पुरुऽमीढः १८. ३, १५.
पुरुऽमीढम् ४. २९, ४.
पुरुऽमील्ह २०. १०३, १.
पुरुऽरूपम् ९. १५, १९; १८. १, १७; २०. ८५, ४.
पुरुऽरूपाः ४. २१, १.
पुरुऽवर्तमानम् ५. २, ७; २०. १०७, १०.
पुरुऽवसुः १४. २, ४७; २०. ५१, १.
पुरुऽवसुम् २०. ५६, ५.
पुरुवसो इति पुरुऽवसो २०. ३६, ४; १०४, १.
पुरुऽवीरम् २०. १४३, ६.
पुरुऽवीरस्य २०. ३६, ३.
पुरुऽवृतः १०. २, ११.
पुरुऽशाक २०. ३७, ६.
पुरुऽशाकः १३. ३, १५.
पुरुष ४. ९, ७; ५. ३०, ६; १७; ८. १, ४; ६; १०; १८. ४, ५१.
पुरुषऽअर्दः १२. १, ४९.
पुरुषऽअस्थे ५. ३१, ९.
पुरुषऽइषिताः २. १४, ५.

पुरुषः ४. ३, १; ५. ३०, २; ६. १०९, २; ८. १, १; २, २५; १०. २, ९; १८; २०; २१; २८[2]; ३०; ११. ६, १४; ७, १३; १२. ३, १०; १९. ६, १; ३; ४; ९; ३९, २; ३; ४; ४४, ८.
पुरुषऽगन्धिः १२. २, ४९.
पुरुषऽजीवनम् १९. ४४, ३.
पुरुषऽजीवनीः ८. ७, ४.
पुरुषता १८. १, ५२.
पुरुषऽतेजाः १०. ५, ३५.
पुरुषम् १. १६, ४; ५. ४, ६; ५, २; ४; ७, २; २९, १; ६. ३०, २; १११, १; १३३, ३; १३८, १; ७. ८०, ४; ८. २, ५; ७, २; ५; ७; ११; १९; २२; ९. १३, ४; ६; १०. १, १७; २९; ११. १०, १३; १८; २९; ३२; १२. ४, १३; २५; १९. ६, ५; ११; १५.
पुरुषऽरेषणः ३. ३१, ९.
पुरुषऽवधाः १२. ७, ३.
पुरुषस्य ५. ७, ८; २८, ३; ६. ३८, ४; ८. ४, १५; १०. २, १; २; ४; ८; ११. १०, ३१; १९. ४९, ४.
पुरुषाः २. २६, ३; ११. २, ९.
पुरुषाणाम् ४. ९, २; ८. ७, १५.
पुरुषात् ५. २१, ४; १९. ६, १६.
पुरुषान् ३. २८, ५; ६; ६. ५९, २; ९. ३, १४; १८. ३, ६२.
पुरुषाय ९. ३, १२; १३. ७, १४.
पुरुषे ३. २१, १; १०. २, १०; ११; १२; १३; १४; ७, १५[2]; १७; ११. ११, ७; १४; १२. २, ५; ३, ५१.
पुरुषेण ७. ५, ४; १९. ६, १०.
पुरुषेभ्यः १. ३१, ४; ३. २८, ३; ३०, ४;

६. २७, ३; १२. २, १६; १९. ४७, ९.
पुरुषेषु ४. १८, ५; ६. ३८, २; १०. १, ४; ११. २, २१; १२. १, १९; २५; २, १.
पुरुषैः ५. १४, ७.
पुरुऽस्तुत २०. ६, २; ७, ४; १५, ४; ६१, ६; ६२, १०.
पुरुऽस्तुतः ६. २, ३.
पुरुऽस्तुतम् २०. ६१, ४; ६२, ८.
पुरुऽस्तुतस्य २०. १९, ४.
पुरुऽहन्मन् २०. ९२, १७; १०५, ५.
पुरुऽहूत २०. ३६, ४.
पुरुऽहूत ४. ३१, ६; ७. ५२, ७; १८. ३, ६७; १९. ५५, ६; २०. १७, २; १०; ३६, ११; ७७, ८; ७९, १; ८९, ७; १०; ९४, १०; १०८, ३.
पुरुऽहूतः ५. ३, ८; १७. १, ११; २०. ४६, २.
पुरुऽहूतम् ७. ९१, १; २०. १९, ५; ६१, ४; ६२, ८.
पुरुऽहूताय २०. ७८, १.
पुरूचीः २. १३, ३; १२. २, २३; १८. २, २९; १९. २४, ५; ६.
पुरूचीम् १०. २, ७.
पुरूणाम् २०. ६८, १२.
पुरूणि ५. १, २; २०. ११, ५; ६; ३१, १; ९४, ७; १०९, ३.
पुरोडाशम् १८. ४, २.
पुरोडाशऽवत्सा १२. ४, ३५.
पुरोडाशाः ८. ८, २२.
पुरोडाशौ ९. ६, १२; १०. ९, २५.
पुरोळाशम् २०. २३, ३.
पुल्वघः २०. १२६, २२.
पुषेम ५. ३, १; १९. ५५, ३.
पुष्करऽपर्णम् ८. १४, ६.
पुष्करम् ११. ३, ८; १२. १, २४.
पुष्करऽस्रजा ३. २२, ४; ५. २५, ३.
पुष्करिणी ५. १७, १६.
पुष्करिणीः ४. ३४, ५; ६; ७.
पुष्कलम् १३. ३, १०.
पुष्टऽपतिः ३. ८, ४; ७. २०, १; ४१, १; १९. ३१, ६; ११.
पुष्टऽपतिम् ७. ४१, २.
पुष्टम् ५. ३, ७; ६. ७९, २; ७. २०, १; ८४, ३; १२. १, २९; १८. २, ६०; ३, ६१; १९. ३१, ६; ११.
पुष्टये १०. ६, २९.
पुष्टानि ४. २४, ७; २०. ३४, ४.
पुष्टाय १४. २, २७.
पुष्टिः ३. २८, ४; १९. ३, ३; ३१, १३.
पुष्टिऽकामाय १९. ३१, १.
पुष्टिम् ९. ४, १९.
पुष्टिम् १९. ३१, ३; ५.
पुष्टिऽमत् २०. १२६, ३.
पुष्टीः २०. ३४, ५.
पुष्टे ३. १०, ७.
पुष्टेषु २०. १२६, १.
पुष्ट्याः ९. १०, २.
पुष्ट्या १९. ३१, २; ९; १३; ४९, ३.
पुष्पम् ५. ४, ४; ६. ९५, २; ८. ७, १२; १०. ८, ३४; १९. ४४, ५.
पुष्पऽवतीः ८. ७, २७.
पुष्पाम् ८. ७, ६.
पुष्पिणीः ६. १०६, १.
पुष्यः १९. ७, २.
पुष्यत ३. १४, २; ४; ५; ७. ६२, ७.
पुष्यतः ७. ५९, २.

पुष्यतम् १४. २, ३७.
पुर्ष्यति ४. ३२, १; २०. २५, ३.
पुर्ष्यते १८. १, २२.
पुष्यन्ति २०. ५६, ६.
पुर्ष्यसि ७. ११, १.
पुष्यसि १३. २, १०; २०. ९५, ३.
पूः १०. २, ३१.
पूःऽभित् २०. ११, १.
पूःऽयानैः १८. १, ५४; ४, ६३.
पूतः ६. ५१, १; २; ११. १, २५; १२. ३, १४.
पूतऽदक्षाः ५. २२, १; ६. ९३, ३.
पूतम् ४. ३९, १०; ६. ११५, ३.
पूताः ४. ३४, २; ६. १२२, ५; ११. १, १७; १८; २७; १२. २, २५.
पूतासः २०. ८४, १.
पूतिऽधान्या ३. १२, ३.
पूतिम् ८. ८, २.
पूतिऽरज्जुः ८. ८, २.
पूतुद्रुः ८. २, २८.
पूतौ १२. ३, ३.
पूत्रिमम् ६. १२४, ३.
पूत्वा १४. १, ४१.
पूरय ३. १०, १३.
पूरयति ३. २९, २.
पूरयाति १२. १, ६१.
पूरवः २०. ७५, २.
पूरुम् २०. ३७, ३.
पूर्णः १०. ६, २; १९. ५३, ३.
पूर्णम् ३. १२, ८; ९. ४, ६; १०. ८, २९[२]; १८. ३, ५४; २०. ७६, ७; ८९, २.
पूर्णा ३. १०, ७; ७. ८५, १[२].
पूर्णाः ४. ३४, ६; ७. ६२, २.
पूर्णात् १०. ८, २९.
पूर्णान् ४. ३४, ७.
पूर्णाम् २. ३६, ५.
पूर्णेन ७. १८, १; १०. ८, १५; २९.
पूर्तम् ९. ५, १३; ८, १; ११. ९, ९; १२. ६, ४; १०, १०.
पूर्तस्य ६. १२३, ५.
पूर्तिऽकामः ७. १०८, १.
पूर्वऽअग्नौ ५. ३१, ५.
पूर्वऽअपरम् ७. ८६, १; १३. २, ११; १४. १, २३.
पूर्वऽआसिनम् १०. १, २७.
पूर्वः १. ७, ४; ५. २०, ६; ८. ३, ७; ९. ८, १; २; ३; ४; ५; ६; ७; १०. ३, ३; ११. ७, ५; १३. २, १४; १८. ४, ८; ९; २८; १९. ३९, ९.
पूर्वकामऽकृत्वने ७. १२१, १.
पूर्वऽकृत्वरि १२. १, १४.
पूर्वऽचित्तये २०. ९, ३; ४९, ६; १०९, ३.
पूर्वऽचित्ताः ७. ८७, ३.
पूर्वऽजनाः १२. १, ५.
पूर्वऽजेभ्यः १८. २, २.
पूर्वऽथा २०. ६१, ३; ९९, २.
पूर्वऽपीतये २०. ९९, १.
पूर्वऽपेये १२. १, ३.
पूर्वम् ४. ३५, २; ३७, १; ८. १, १०; ९. ५, २७; १२. २, २५; १४. १, ६४; २, २०; १८. ४, १५; ४४; २०. २६, ३; ६७, ७.
पूर्वऽयावा २०. ११, २.
पूर्वऽरूपाणि १९. ९, २.
पूर्वस्मात् ११. २, २५; ७, ६.
पूर्वस्य १०. १, २७.

पूर्वऽहूतिः ७. २६, १; २.
पूर्वऽहूतौ १९. १०, ५.
पूर्वा ६. १६, ४; १३३, २; ११. १०, ७; १४. २, ७४; १९. ७, ३; ४.
पूर्वाः १९. ३४, ७.
पूर्वान् ५. ३०, १; १०. ३, १३; १४; १५.
पूर्वाम् १६. ७, ९; २०. ९२, १५.
पूर्वासः १८. १, ४६.
पूर्वा इति २०. ७६, ६.
पूर्वाः ४. २१, १; २०. १६, १२; ५९, ४; ७३, ३; ७६, ५; ८; ११९, १.
पूर्वे २. ३४, ५; ४. १, ६; ५. १७, ६; ८; ६. ६४, १; १३३, ५; ७. ५, १; ८. ६, १४; ९. ११, ३; ११. २, १८; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १२. १, ५; ३९; १८. १, ५०; ५४; २, १५; ३, ७२; ४, ४४; १९. २६, २; २०. ३६, २.
पूर्वेण १०. ४, ३.
पूर्वेभिः २०. ३०, ५.
पूर्वेभ्यः १८. २, २.
पूर्वेषाम् २०. ३२, ३.
पूर्वैः १८. ३, ४८.
पूर्व्यः ७. २२, १.
पूर्व्यम् २०. ९९, १.
पूर्व्यम् ५. १, ४; १८. ३, ३९; २०. ७७, ८; १०३, ३; ११९, १.
पूर्व्यऽस्तुतिम् २०. ६४, ५.
पूर्व्यस्य ४. १, ६.
पूर्व्या २०. १४३, ५.
पूर्व्याः १९. ३४, ६.
पूर्व्याणि २०. ३५, १३.
पूर्व्याय २०. १४३, ३.
पूल्यानि १४. २, ६३.
पूषणम् ३. १६, १; ४. ३०, ६; ११. ८, ३; १८. २, ५३.
पूषन् ७. १०, ३; १४. २, ३८.
पूषन् १. ११, १; ६. ११२, ३; ११३, २; १४. १, ३९.
पूषा १. ९, १; ३. १४, २; १७, ४; ५. २८, ३; १२; ६. ६७, १; ७३, ३; ७. १०, १; २; ४; ३४, १; १४. १, १५; ३३; १६. ९, २; १८. २, ५४; ५५; १९. १०, ९; २०, १.
पूषेम १९. ६७, ५.
पृणः १९. ५१, २.
पृक्षः २०. १४३, २.
पृच्छ २०. ६८, ४.
पृच्छन्ति २०. ३४, ५.
पृच्छन्ति १२. १०, ४.
पृच्छन्ती २०. ३६, ५.
पृच्छमानौ १४. १, १४.
पृच्छाम ८. ९, ७.
पृच्छामि ९. १५, १३'.
पृच्छामि ८. ९, १; ९. १४, ६; ७; १०. ८, १०; ३४; ११. ३, २२; १२. ४, ४३.
पृच्यध्वम् ६. ६४, १.
पृच्यन्ताम् ६. ७४, १.
पृञ्च ९. ४, २३.
पृञ्चतीः १. ४, १.
पृञ्चन्ति ५. २, ३; २०. १०७, ६.
पृञ्चे ६. १२, ३.
पृण २०. १५, ५.
पृणक्षि ५. १, ९; २०. २५, १.
पृणत् ७. ५९, १.

पृणतः १. २७, ४.
पृणन्तः ६. १४२, ३.
पृणन्ति १८. ४, २९; २०. ३०, २.
पृणन्ति २०. १२६, १४.
पृणस्व २. ५, २; ४.
पृणस्व ७. २७, ८; १९. ६१, १; २०. ३३, १.
पृणाति ६. २२, ३.
पृणाति ११. ७, ४.
पृणातु १९. ५९, २.
पृणीत १. ६, ३.
पृणीहि १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४.
पृतनाः ५. ३, १; १४, ८; २०, ४; ६. ९७, १; ८. ५, ८; १०. ५, ३६; १३. १, २२; १६. ९, १; १९. ३२, १०; २०. ११, ४; ५४, १; ७६, ८.
पृतनाऽजितम् ७. ६५, १.
पृतनाऽजिम् ७. ९०, १.
पृतनाज्ये २०. १९, ७.
पृतनानाम् २०. ९२, १६; १०५, ४.
पृतनाऽयतः १९. २८, ५; ६; ७; ८; ९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९; ३२, ६.
पृतनाषाट् ११. १, २; १९. १३, ७.
पृतनाषाट् ५. १४, ८.
पृतनाऽसहम् २०. १०८, १.
पृतनाऽसह्याय २०. १९, १.
पृतनासु ३. २१, ३; ४. २७, ७; २८, ७; ३२, ४; ५. २९, ११; ८. ३, १८; १९. ५२, २; २०. ७५, ३; ७६, ८; ९२, १९.
पृतन्यतः १. २१, २; ७. ७३, ३; ९८, १; १९. ३२, १०; ४६, २; २०. १७, ६; ७०, २०.
पृतन्यति ६. ७५, १; १३. १, २९.
पृतन्यन्तम् १. २९, २.
पृतन्यवः ७. ३५, १; ६४, १; ११. १, ९; ११.
पृतन्यात् १२. १, १४; १९. ४६, ५.
पृतन्यान् ३. १९, ३.
पृत्ऽसु २०. ६१, १; ९०, २; १४१, ३.
पृत्सुतूर्षु २०. १९, ७.
पृथक् ३. १७, १; १९, ६; ४. १५, २; ३^{२}; ४; २०, २; ५. २०, ७; ७. ४७, १; ९. १, ३; ११. ७, २; १३; २२; १२. ३, २१; २०. ७२, १^{२}; ९४, ६.
पृथक्ऽसहस्राभ्याम् १९. २२, १९.
पृथिवि ७. १९, १; १२. १, ११; १२; १४; १५; १६; २३; २४; ३०; ३६; ४६; ४९; ६२; १८. २, १९; ३, ५०.
पृथिविसत्ऽभ्यः १८. ४, ७८.
पृथिवी २. १५, १; २८, ४; ३. ९, १; २३, ६; ४. २, ४; ३९, २; ५. ९, ७; २५, २; ६. १७, १; २; ३; ४; ४४, १; ५३, १; ७७, १; ८८, १; १००, १; ७. १९, २; ८. १, १२; १७; ४, २३; ७, २; १२, १०; ९. १, २१; १२, २; १५, १२; २४; १०. १०, ४; ३०; ११. १, ८; २, १०; ३, ११; ७, ४; ११, ४; १२. १, १; २; ५; २१; २२; ३७; ४१; ४४; ४५; ४८; ५२; ५३; ५९; ३, २०; ४, २३; १३. १, १७; १४. १, २; २, ७१; १५. १०, ६; १८. १, ५; २, २५; ३, २५; २७; २८; ३०; ३१; ३२; ३३; ३४; ३५; ४९; ५१; १९. ९, १; १४; ५४, २; ५८, २; २०. १५, ५; ७६, ६; ७७, ७; १०६, २.
पृथिवी इति २०. ३४, १४.

पृथिवीऽइव ९. ४, २.

पृथिवीः ४. २०, २; ६. २१, १; ८. ४, ११; १९. २७, ३; ३२, ४; ५३, ५.

पृथिवीऽप्रः १३. २, ४४.

पृथिवीम् १. २, १; ४; ३. ८, १; ९, ६; २१, ७; ४. २, ७; ११, १; १५, १; ४; ५; ७; ८; ९; २७, ४; ३५, ३; ६. २२, १; ६०, ३; ६१, २; ३; १२०, १; १२६, १; ७. ७, १; ८. २, १५; ९. ३, १५; ५, १५; १५, २२; १०. ५, २५; ४५; ८, ११; ३६; ११. २, १०; ६, ५; १७; ७, १; ८; ९; १२. १, १; ७; ११[2]; १७; २७; २९; ४३; ५७; ३, २२; २३; २५; २६; २८; ४०; १३. १, २५; ३४; ४५; २, ५; ४५; ३, २२; १४. २, ६९; १५. १०, ९; १८. १, ३९; २, ७; ४९; ३, २६; ४९; ५२; ४, ५; ६; २८; ४८; १९. ३२, ९; ५८, ३[2]; २०. ११, ८; ३४, २; ७५, २.

पृथिवीऽसंशितः १०. ५, २५.

पृथिव्या ४. ३०, ८; ११. ४, १०; १२. ३, २३; १८. १, १०; १९. १९, १.

पृथिव्याः १. २४, ४; २. ३, ५; ७, ३; ४. १, ४; १४, ३; ५. २, ७; १०, ८; १२, ४; १७, ११; ६. ४३, २; ८६, १; २; १००, ३; १०५, २; १२५, २; १३४, २; ७. ९, १; १०, १; २७, ८; ८. ४, ४; ९, १; ९. १, १; १५, १३; १४; १०. ५, २५; ११. २, २७; ७, ११; १२. १, ४; ८; १२; ३, ३५; ११, ११; १३. १, १६; ३८; १४. १, ४७; २, ७०; १५. ७, १; १६. ४, ४; ७, ६; १८. २, २०; ५२; १९. ३, १; ३५, ४; २०. ३५, ९; ७६, ७; १०७, १०; १४३, ५; ९.

पृथिव्याम् १. ३, १; २; ३; ४; ५; ३०, ३; ३२, १; ४. ८, ५; ३९, १[2]; ६. ८०, ३; १३६, १; ७. ६४, १; १०२, ८; ८. ७, १३; ९, २५; २६; ९. १, ३; २, १४; ३, १६; १७; ११, ७[2]; १०. ३, १९; ४, २२; ११. ७, १२; २६; ८, १२; १२, २; १२. १, १३; ३, २२; १३. २, ३०; १५. १३, २; १७. १, १२; १३; १८. २, ३६; ४, ४८; १९. २७, १३; ३२, ३; ४४, ३.

पृथिव्यै १. ३२, ४; ५. ९, २; ६; ६. १०, १; २०, २; १२. १, २६.

पृथ्वी ८. ३, ११; २०. १४०, ५.

पृथु १३. २, २२; २०. ४७, १९; ७१, १३; १३९, १.

पृथुः ७. १२, १; १३. ९, १; २०. ६४, १.

पृथुऽजघने २०. १२६, ८.

पृथुऽज्मन् ५. १, ५.

पृथुऽज्रयम् २०. १४३, १.

पृथुऽबुध्नः १२. ३, १४.

पृथुऽशिराः ५. १७, १३.

पृथुऽस्तुके ७. ४८, १.

पृथुस्तो इति पृथुऽस्तो २०. १२६, ८.

पृथूनि १९. ५८, ४.

पृदाकवः १०. ४, ११; १३; २०.

पृदाकवे १२. ३, ५७.

पृदाकुः ३. २७, ३.

पृदाकुम् १०. ४, १७.

पृदाकूःऽइव ५. १८, ३; १५.

पृदाकोः ७. ५८, १.

पृदाकौ ६. २८, १.

पृदाक्वः १. २७, १.

पृदाकम् १०. ४, १७.
पृदाकाः १०. ४, ५.
पृशनऽयुर्वः २०. १०९, २.
पृश्नयः ८. ७, १; २०. १०९, २.
पृश्नि १. ११, ४.
पृश्निः २. १, १; ६. ३१, १; १०. ५, २०; १९. ११, ३; २०. ४८, ४.
पृश्निऽपर्णि २. २५, ३.
पृश्निऽपर्णि २. २५, ४.
पृश्निऽपर्णी २. २५, १; २.
पृश्निऽबाहवः ४. १५, १२.
पृश्निऽबाहुः ८. ८, १७.
पृश्निम् ५. ११, १; २; ८; १७, १७; ७. १०९, १; ९. १५, २५.
पृश्निऽमातरः १३. ३, २३.
पृश्निऽमातरः ५. २१, ११; ८. ७, २१; १३. १, ३.
पृश्निऽमातॄन् ४. २७, २.
पृश्निऽहा १०. ४, १५.
पृश्नेै ५. १३, ५.
पृषत् १. २३, २; ३.
पृषत्ऽआज्यम् १९. ६, १४.
पृषती १३. १, २१; २३.
पृषतीभिः २०. ६७, ४.
पृषतीम् १३. १, २४.
पृषदाज्यऽप्रनुत्तानाम् ११. १२, १९.
पृषन्तम् २०. ८८, २.
पृषातकी १४. २, ४८.
पृष्टः ७. ५७, १.
पृष्ट्यः ४. ३, ६; ९. १२, ६.
पृष्टिऽआमयम् १९. ३४, १०.
पृष्टिऽवाहः १८. ४, १०.
पृष्टीः २. ७, ५; ३२, २; ५. २३, ९; ६. ३२, २; ५०, १; ८. ३, १०; ९. १३, १५; १०. २, ४; ९, २०; ११. १०, १४; १६. ७, १२; १९. ४५, १.
पृष्टीभिः १२. १, ३४.
पृष्ठ्याम्ऽइव ६. १०२, २.
पृष्ठम् ४. १४, २; ३४, १; ९. ५, २०; १५. १, ७.
पृष्ठात् ४. १४, ३[२]; ११. ७, १०; १८. ४, १४.
पृष्ठानि १२. २, १२; १८. १, ६१.
पृष्ठे ५. २०, ६; ७. ८५, १; ९. ५, १०; १५; १४, १०; १५, ९; १०. ७, ३८; १०, ५; ११. ७, २६; १२. २, ४१; १३. २, ३७; ४, १; १८. २, ४७; ४, ४; ३६.
पृष्ठेन ११. ४, ९[२].
पेततुः ७. १००, १.
पेत्वः ५. १९, २.
पेत्वस्य ४. ४, ८.
पेपिशाने इति ८. ९, १२.
पेरुः १९. ११, ३.
पेशः २०. २६, ६; ४७, १२; ६९, ११.
पेशनीः १०. २, १.
पेष्ट्रम् ४. १२, २.
पेष्ट्रम्ऽइव ६. ३७, ३.
पैद्व १०. ४, ६.
पैद्वः १०. ४, ५[३]; ७; १०.
पैद्वस्य १०. ४, ११.
पोत्रात् २०. २, १; ४; ६७, ४; ७.
पोषः ९. ४, ७.
पोषम् १. ९, ४; २. १३, ३; २९, २; ३. २०, १०; ४. २५, ५; ३९, २; ४; ६; ८; ५. २७, १०; ७. ४१, २; ४९, २;

१८. १, ४३; ४, ४७; १९. २४, ५; ५२, १.
पोषय ३. २८, ४.
पोषयिष्णु ५. २८, ४.
पोषयिष्णुः ३. १४, ६.
पोषाः २. ३४, १; ५. २८, ३.
पोषाय ६. १४१, १; १९. ३१, १३.
पोषे ३. १०, ७; ९. ४, २.
पोषेण ३. १०, ३; ८; १४, ६; १९, ८; ६. ५, २; १९. ५५, १; २.
पोषैः ९. ४, २२; २४; ११. १, ३४; १८. ४, ६२.
पोष्या १४. १, ५२.
पौंस्यम् २०. ७३, ६; ९७, ३; १०६, २.
पौंस्या २०. ६७, २; ६९, ७.
पौंस्यैः २०. ७६, ७.
पौञ्जिष्ठःऽइव १०. ४, १९.
पौत्रऽआद्यम् १२. ८, १.
पौत्राः ११. ९, १६.
पौत्रम् ९. ५, ३०; १२. ३, १४; १८. ४, ३९.
पौत्रान् १२. ४, ३८.
पौरः २०. ११८, २.
पौरुऽकुत्सिम् २०. ३७, ३.
पौरुषेयः १. ३०, १.
पौरुषेयम् ८. ६, २३; १२. ३, ४९; १९. २०, १.
पौरुषेयात् ४. २६, ७; ७. ११०, १; १०. ३, ४.
पौरुषेये ११. ११, १०.
पौरुषेयेण ८. ३, १५.
पौर्णऽमासम् ७. ८५, २.
पौर्णऽमासी ७. ८५, १; ४; १५. २, १४; १६, १.
पौर्णऽमासीम् १५. १७, ९.
प्यायताम् ४. १५, ११; ५. २९, १२; १३; ६. ७८, १.
प्यायन्ताम् १२. ३, २०.
प्याययति ४. ११, ४.
प्याययन्तु ७. ८६, ६.
प्याययामि १८. ४, ६४.
प्यायसे १४. १, ४.
प्यायस्व ७. ८६, ५.
प्याशिषीमहि ७. ८६, ५.
प्र १. ३, ७; ७, २; ४; ५; १०, २; १६, २; १८, २; २४, ४; २७, ४[२]; २८, १; ३०, १; २. १, २; ४, ६; ५, १; ५[२]; ६, २; ७, १; १०, ५; १३, २; २५, ५; ३२, ६; ३४, ३; ४; ३५, ३; ३. १, २; ४; २, २; ५; ४, ५; ६, ७; ८[३]; ११, १; ५; १२, ८; ९[२]; १४, ४; ५; १६, ३[२]; १८, ६; १९, ७; ८; २०, २; ३[५]; ९; २३, ६; २९, १; ३१, ९; ४. १, ३[२]; ७, ४; ८, २; ९, ५; १०, ६; १२, ६[२]; १४, ५; ९; १५, ९; ११; १३; १६, ४; २०, ९; २५, ३; ६; २७, १; २८, ४; २९, १; २; ५; ६; ३०, ८; ३१, १; ३; ३२, ७; ३३, ३[२]; ४[२]; ५; ३४, २; ३६, १; ३७, १०; ५. १, ४; २, ७; ६, ४; ११[२]; १२[२]; १३[२]; १४[२]; ७, ३; ११, ६; १७, २; २०, ६; ८; ११; २१, ४; ५; ६; ११; २२, ४; ८; २८, ९; २९, ४; ३०, ९; ३१, १०; ६. ४, ३; १४, ३; २४, १; २८, १; ३४, १; ३५, १; ३७, १; ८३, १; ३[२]; ८८, ३; ९७, २; १०५, १; २; ३; ११०, ३; ११३, २; १२१, ३[२]; १२६, ३; १२८, १; १३०, १; २; ३;

१३१, १; २; १३४, १; **७.** २, १; ५, २; ५; ९, १; १९, १; २; २६, २; २७, १; २; ३५, १; ३६, १; ४३, १; ५१, १; ५२, ३; ४; ५५, ५; ६६, २; ७५, २; ७७, ५; ७; ८२, ३; ८३, २; ८६, २; ८८, ४; ९४, ३; १०२, ३; ११९, २[२]; १२०, १[२]; ३; **८.** १, ५; ७; १०; ११; २, १; १७; ३, ४; ८; ९; २४; ४, ३; १७; १९; २२; ६, ८; १७; ८, १०; १९; ९, १०; १२, ४; ६; **९.** १, ६; ७; २, ४; ६; १२; १४; १७; १८; ३, ६; २२; २३[२]; ५, ३; ८; १६[२]; २३; ६, ३; ४; १०, १; ४; ६; ८; १४, १८; १५, ३; ४; **१०.** १, १५; ३०; २, १५; २६; ३, १; २[२]; १५; १६; ४, ६; २५; ५, २३; २४[३]; ५०[२]; ७, ८; ९[२]; २८; ४२; ८, ७; १९; २३; ९, ३; ११; १०, ७; १४; **११.** १, १८; २२; २५; ३, २६; २७; ३१; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ६, ३; ४; ५; ६; १४; १६; १७; २०; २२; ७, १५; ८, २३; १०, ११; १९; २०; २१; २२; २३; २४; २५; २७; ३०; ३१; ११, १; १५; २२; २४; १२, १८[२]; **१२.** १, १८; ४१; २, ३; ४; ८; १०; १३; २६; २७; ३४; ३५; ३८; ४५; ३, १५; १८; ३१; ३२; ३८; ४३; ४५; ४, ४७; १०, ५; ११; १४; ११, १[२]; ६[२]; १२; **१३.** १, १; ३; २७; २९[२]; ४३; ५९; २, ३१; ३२; ३७; ४६[२]; ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; **१४.** १, १३; १७; १८; १९; २०; २४; ५८; २, १५; १९; २१; २६; ५९; ६०; ६१; ६२; ६७; ६९[४]; ७५; **१५.** १, २; ३; ८; १०, ३; ४; ५; १२, ५[२]; **१६.** १, ११[२]; ४, ५; **१७.** १, २८; २९; **१८.** १, ५; ७; २४; ५४[२]; ६१; २, २; ३; ४; २८; ३१; ३९; ५३; ५४; ५८; ३, ८[२]; ९; ३८; ४२; ४३; ६५; ७३; ४, १४; २९; ४०; ४८; ४९; ५१; ६०[२]; ६५; ७०; **१९.** ६, ११; ७, ३; ८, २[२]; १३, ७; १७, १; २; ४; ५; ६; ७; ८; ९; १०; १९, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; २०, ४; २४, ४; ३२, २; ३; ३४, ४; ३७, १; ४०, २; ४२, ३; ४६, ४; ४९, ९[२]; १०[२]; ५०, ४; ५६, १; ५७, ३; ६४, १; ७१, १; **२०.** ५, १; ३; ६; ६, ३; ४; ११, २; ३; ४; ५; ९; १३, २; १४, ३; १५, १; १७, ४; १८, ४; २१, १; २२, ४; २५, २; ७; ३०, १[२]; ३१, ४; ३२, १; ३३, २; ३५, १; २; ९; १२; १३; १५; ३७, १; ३[२]; ४४, १; ५१, १; २[२]; ३; ५६, १; ६१, ४; ६२, ३; ८; ६८, ८; ११; ७३, ३[३]; ७६, २[२]; ५; ७[२]; ७८, ३; ८७, ३; ५[२]; ८९, १; २; ८; ९१, ३; १२; ९२, १; ५; ९४, ६; ९६, ६; ९७, २; १०७, १०; १२६, २; १३७, ३; १३८, २; १३९, १; १४२, १; २[४]; ४; ५[४].

प्र॒ऽअर्ज॑नात् **४.** ६, ५.

प्र॒ऽअनु॑दन्त **९.** २, १७; १८.

प्र॒ऽअपा॑दि **५.** १७, ४.

प्र॒ऽअ॒यम् **४.** २५, २.

प्र॒ऽअर्थैः **५.** २२, ९.

प्रऽअविंशत् १०. ७, ८.
प्रऽअशितारः ११. १, २५; ३२.
प्रऽअश्नती ६. १३३, २.
प्रऽअश्नन्ति ८. ७, २५.
प्रऽअर्हैत् २. २४, १; २; ३; ४; ५; ७; ६; ८.
प्रऽआंप्तः ९. १२, २२.
प्रऽआंप्तिः ११. ९, २२.
प्रऽआप्नोषि ४. १९, २.
प्रऽआवृत्यं ११. १०, १५.
प्रऽआशीः ११. ३, २८; २९; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८.
प्रऽआश्नन् ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८.
प्रऽईतम् १८. ३, १.
प्रऽइयार्य १८. ३, १३.
प्रऽईव १२. २, ५२.
प्रऽईषिता ११. ३, १४.
प्रऽईषिताः ३. १३, २.
प्रऽईषितौ ८. १, ९.
प्रऽईक्षंते ९. ७, १.
प्रऽईङ्खाः ४. ३७, ५.
प्रऽईप्संन् १०. ७, ४[२].
प्रऽईप्संन्तीः १०. ७, ४; ६; ३७.
प्रऽईयुः ५. ८, ६; ११. १२, १७.
प्रऽउक्षंणीः १०. ९, ३.
प्रऽउक्षंणीभिः ५. २६, ६.
प्रऽउक्षन्ती १०. ९, ११.
प्रऽऊढः १५. १५, ४.
प्रऽएषाः ५. २६, ४; ११. ९, १८.
प्रऽएषैः १६. ७, २.
प्रऽएष्यन् ५. २२, १४.
प्रऽकंल्पयन् १९. ८, १.
प्रऽकशः ९. १, २१.
प्रऽकुंपितान् २०. ३४, २.
प्रऽकृन्तति १२. ४, ७.
प्रऽक्रामंन्तः १२. १, २८.
प्रऽक्रीः ४. ७, ६; ११. ९, १०.
प्रऽक्रीडंते ५. २१, ८.
प्रऽक्षींणाः १०. ३, १५.
प्रऽगृंहीतम् १२. ४, ३४.
प्रऽचक्रुः १२. २, ५.
प्रऽचरंते ९. ३, १२.
प्रचंर्षणी इति प्रऽचंर्षणी ७. ११५, २.
प्रऽचेतः ४. ३२, ५; ७. १११, १; ८. ३, ९.
प्रऽचेंतसः ४. २३, १; ६. ६८, १; ८. ७, ७; १४. २, ४६; २०. १०९, ३.
प्रऽचेतसा २०. १४१, ५; १४२, ५.
प्रऽचेंतसे २०. ६९, ५; ७३, ३.
प्रऽचेंतसौ ६. ५३, १.
प्रऽचेंताः ५. १२, १; ६. ४५, ३; १८. २, २७.
प्रऽचोदयंः २०. ६३, ९.
प्रऽचोदयंन्ता ५. १२, ७.
प्रऽच्यवंते ९. १३, ३.
प्रऽच्यवंन्ते ८. ९, ८.
प्रऽच्युंतः ६. १२१, ४.
प्रऽच्युंताः ४. १५, ७; ८; ९; ५. २०, ३.
प्रऽच्युंताम् ८. ९, ८.
प्रजनंनऽवन्तम् १९. १८, ९.
प्रजनंनऽवान् १९. १७, ९.
प्रऽजनंनाय ९. ९, १०.
प्रऽजनयंन् १०. ७, २६.
प्रऽजन्वः ९. ४, ६.
प्रऽजया २. ३४, ३; ४; ३. २९, ८; ५. ३, ७; २९, ६; ७; ८; ९; ६. ५, १; १४१,

२; **७.** १८, ४; ३४, १; ८६, २; ४; ५; ९४, २; **९.** १, १५; **१०.** ५, ४७; ६, २३; **११.** १, १; १४; २०; २१; **१२.** ३, १०; ४, २; **१४.** १, ३२; ३३; ४८; ५३; ५४; २, १; १३; ६४; ७०; **१८.** ३, १७; **१९.** २४, ८; ३१, ७; ६४, २.

प्रऽजहितानि॑ **२०.** ११६, १.

प्रऽजा **७.** ३६, ३; **९.** १२, १३; **१०.** ६, ३३; **११.** १, १९; ४, १; ४; **१२.** ६, ४.

प्रजाऽअमृतत्वम् **११.** १, ३४.

प्रऽजाः **२.** ३५, २; **७.** २०, १; ११६, १; **९.** १, १; २४; ४, २०; **१०.** ८, ३; ३७; ३८; **११.** ६, १०; १९; **१२.** १, १६; **१३.** १, १९; **१५.** १४, २१; १५, ९; **१६.** ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; **१९.** ५३, ७; १०.

प्रजाऽका॑माय **७.** १८, ३.

प्रऽजा॑तम् **९.** १४, १८; **१९.** २६, १.

प्रऽजा॑ता **१.** ३४, १.

प्रऽजा॑तेन **६.** ८९, १.

प्रऽजानती **१८.** ३, ४.

प्रजानती इति॑ प्रऽजानती **८.** ९, १२.

प्रऽजानतीः **१२.** २, ४१.

प्रऽजानन् **२.** २६, २; **३.** १२, ४; २०, ८; **४.** २३, २; **५.** २६, २; **६.** ११२, १; २; **७.** १०, १; २; **८.** ९, २२; **९.** ५, १; ३; **१२.** २, ८; **१४.** १, ५९; **२०.** ८६, १.

प्रऽजानन्तः **२.** ३४, ५; **१३.** ३, १७.

प्रऽजाना॑म् **५.** २४, १३; **९.** १, ४; ९, १०[२]; **१०.** १, २१; **१७.** १, ३.

प्रजाऽप॑तिः **२.** ३४, ४; **३.** १५, ६; **४.** ४, २; ११, ७; १५, ११; ३५, १; **५.** २५, ५; **६.** ११, २; ३; ६८, २; ६९, ३; **७.** १८, ४; २०, १; २५, १; **८.** १, १७; ५, १०; **९.** १, २४[२]; ३, ११; १२, १; २४; १५, २४; **१०.** ७, ७; ८; ४१; ८, १३; १०, ३०; **११.** ५, ३; ७, १६[२]; ९, ३; १०, ३०; ११, २५; **१२.** १, ४३; ६१; **१३.** २, ३९; ३, ५; **१४.** २, १३; ४०; **१५.** १, २; ६, २५; ७, २; १४, २१; **१७.** १, १८; **१९.** ९, ६; १२; १७, ९; १९, ११; २०, २; ४६, १.

प्रजाऽप॑तिम् **१०.** ७, १७; **११.** ६, १२; ७, ७; ८, ११; **१५.** १, १; **१९.** १८, ९; ५३, १०.

प्रजाप॑तिऽसृष्टः **१०.** ६, १९.

प्रजा॑ऽपते **५.** २५, १३; **७.** ८५, ३; **९.** १, २४.

प्रजाऽपते **३.** २४, ७; **९.** १, १०; २०; **१०.** ५, ४५.

प्रजाऽप॑तेः **३.** १०, १३; **४.** ११, ११; **७.** १३, १; **९.** ७, १२; **१०.** ५, ७; ८; ९; १०; ११; १२; १३; १४; **१५.** ६, २६; **१६.** ८, ११; **१७.** १, २७; **१९.** ५३, ८.

प्रजाऽप॑तौ **१०.** ३, २४; ७, ४०; **११.** ७, १५; **१२.** ४, ४७.

प्रऽजाभि॑ः **१९.** १९, ११.

प्रऽजाभ्य॑ः **४.** १५, १०; **९.** १, २४; **१३.** ४, ११; **१९.** १०, १०; २०, २.

प्रऽजाम् **१.** ८, ३; **२.** ७, ४; २९, २; **३.** १०, ३; ८; **४.** ११, ९; १९, १; ३९, २; ४; ६; ८; **५.** १८, १२; १९, ११; **६.** ८१, १; **७.** २१, २; ४८, १; ७०,

१; ८७, २; ८. ५, १६; ९, १३; ९. ४, २२; ८, ४; १०. १, १९; ३१; २, २९; ६, ३५; ११. १, ९; १७; २, २१; १३. १, ३४; १४. १, ४२; २, १४; २४; ३१; ३७; ३९; ४०; ७१; ७४; १८. ३, १; ४, ६२; १९. ६३, १; ७१, १; २०. ६३, १; ९६, १५; १६; १२४, ४; १३८, २.

प्रऽजायंते ९. ३, २०.

प्रऽजायाः ९. १०, ३; ५; ७; १०.

प्रऽजायाम् ६. ५५, २; १४. २, ६२.

प्रऽजायै १. १८, १; ५. ३, ७; ८; २५, ८; ८. ६, २१; ९. ३, ११; १४. १, २१; ४७; १८. ३, ४१.

प्रजाऽवत् ६. ९७, २; १२. ४, १; १४. २, ७३; २०. ३३, ३.

प्रजाऽवति ९. ३, १३; १४.

प्रजाऽवति १४. १, ५२.

प्रजाऽवती ११. १, १४; १४. २, १८; ३२.

प्रजावती इति प्रजाऽवती १०. १, २१.

प्रजाऽवतीः ४. २१, १; ७; ७. ७९, १.

प्रजाऽवतीम् १४. २, ७.

प्रजाऽवन्तः ७. ७८, ४; १९. २६, २.

प्रजाऽवन्तम् ७. २१, ३.

प्रजाऽवान् ६. ६८, ३.

प्रजाऽवित् ११. १, १५.

प्रऽजासु ३. १५, ७.

प्रऽज्ञानाम् १३. २, २.

प्रऽज्ञानाय ११. ५, ४.

प्रऽज्ञानीः १०. ७, ३४.

प्रऽतङ्कम् ४. १६, २; ५. १३, ८.

प्रऽततामह १८. ४, ७५.

प्रऽतन्वतीः ८. ७, ४.

प्रऽतरणः ६. १२५, १; १२. २, ४९.

प्रऽतरणम् १९. ४४, १.

प्रऽतरणी १४. २, २६.

प्रऽतरम् ५. १, ४; ६. ५, २; ४१, ३; ८. २, २; ११. १, २१; १२. २, ३०; १८. १, १; २, ३१; ३, १०; १७; ६३; ४, ५४; २०. २१, ११; ८९, १.

प्रऽतरीता १८. ४, ५८.

प्रऽतानाः ६. १३९, १.

प्रति १. ७, ३; ८, २; २८, २[२]; २. ११, ३; १९, १; २; ३; ४; २०, १; २; ३; ४; २१, १; २; ३; ४; २२, १; २; ३; ४; २३, १; २; ३; ४; ३४, ५[२]; ३. १, १; ३; ३, ५; ४, ३; ८, २; १०, ६; १३; १२, २; २९, ७; ८; ४. १२, ६; १४, ९; १८, ४; २०, १; ५; ५. ७, ६; ८, ५; १४, ३; १२; २८, ८; २९, ४; १४; १५; ३०, १३; ३१, १; २; ३; ४; ५; ६; ७; ८; ९; ६. ३१, ३; ३२, १; ३६, २; ३७, ३; ११७, २; ११९, २; १२३, ५[२]; १२५, ३; ७. ३०, १; २; ३५, १; ३६, १; ५५, १; ६०, १; ७२, १; ७७, ३; ८२, २; ८७, ५[४]; ८. ३, ६; १०; १९; २१; २३; ४, ७; ११; २५; ६, २६; ८, १०; ९, १९; ९. १, १; २, २; ३; ३, १५[२]; २४; ४, २४; ५, ३७; १०, २; ५; ७; ८; ९; १३, १३; १५, २; ७; १०. १, १५; २७; २८; ६, ६; ७; ८; ९; १५; १७; २१; ३०; ३५; ८, ३६; १०, २; २५; २७; ११. १, ८; १४; १८; २, १८; १२, १६; १२. २, २९; ३, २३; ४४; १३. २, ४६; ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११[२]; १२; १३;

१४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; १४. १, ३९; २, १५; २५; ३१; १८. १, २८[४]; २, ७; ३७; ३, ४०; ४, ५; ५१; ५२; १९. ४, ४; २५, १; ३१, १३; ३७, २; ४२, ३; ४५, २; ४९, ८; ५७, ५; २०. १५, ४; १८, ६; ४८, ६; ५८, १; ६७, ५; ७१, १०; ९२, १७; ९३, २; १०५, ५; १०७, १५.

प्रतिऽअक्षम् ९. ६, १; १०. ७, २४; २९; ३०; ११. १०, ३.

प्रतिऽअभिचरणः २. ११, २.

प्रतिऽअमुंचम् १०. ६, ३४.

प्रतिऽअर्पयित्वा १२. २, ५५.

प्रतिऽअष्ठीवन् ५. १९, ३.

प्रतिऽआतिष्ठन्ती ५. ५, ३.

प्रतिऽआदाय १०. १, २७.

प्रतिऽआश्रावयति ९. ११, २.

प्रतिऽआहन्ति ८. १५, ३.

प्रतिऽआहन्ति ८. १५, ३.

प्रतिऽआहन्मि ८. १५, २.

प्रतिऽआहन्यात् ८. १५, १; २.

प्रतिऽआहन्यात् ८. १५, २.

प्रतिऽइत्य १९. ४९, ९.

प्रतिऽउदैत् ७. ३, १.

प्रतिऽएतु ३. १, २; २, १.

प्रतिऽकामम् १८. ३, ४६.

प्रतिऽकामाय २. ३६, ७.

प्रतिऽकाम्यः २. ३६, ५; ६; ८.

प्रतिऽकाम्यम् ६. ६०, ३.

प्रतिऽकाशः ९. १३, ६.

प्रतिऽकूलम् ५. १४, १३; १०. १, ७.

प्रतिऽक्रोशे ४. ३६, ३.

प्रतिऽगृहीतः ९. ५, १२.

प्रतिऽगृह्णतः ९. ३, १६.

प्रतिऽगृह्णन्तम् ३. २१, ४.

प्रतिऽगृह्णाति ९. ३, ९.

प्रतिऽगृह्य ३. २९, ८.

प्रतिऽग्रहीता ३. २९, ७; ४. ११, ५.

प्रतिऽघ्नाना ११. ११, ७.

प्रतिऽघ्नानाः ११. ११, १४.

प्रतिऽचक्षणे १. १८, ३.

प्रतिऽचार्कशान् ६. २९, ३[२].

प्रतिऽच्यवीयसी २०. १२६, ६.

प्रतिऽजग्रह ६. ७१, १.

प्रतिऽजनाः ३. ३, ५.

प्रतिऽदहन् ३. १, १; २, १.

प्रतिऽदीव्ने ७. ११४, ४.

प्रतिऽदीव्यति ७. ११४, ४.

प्रतिऽधर्यः १४. १, ८.

प्रतिऽधाम् ८. ८, २०; ११. १२, १६.

प्रतिऽधुक् ९. ४, ४.

प्रतिऽनन्दनम् ७. ३९, १.

प्रतिऽनन्दन्ति ३. १०, २.

प्रतिऽनुदन् ५. ३, २.

प्रतिऽपणः ३. १५, ४.

प्रतिऽपश्यति ९. ६, ३.

प्रतिऽपश्यथ ७. १४, २.

प्रतिऽपानाय १९. ५२, ३.

प्रतिऽप्रहिण्मः १०. १, ५.

प्रतिऽप्राशः २. २७, १; २; ३; ४; ५; ६.

प्रतिऽबुद्धाः ४. ३७, ३; ४; ५.

प्रतिऽबुध्यमानाः १२. १, ६२.

प्रतिऽबोधः ८. १, १३.

प्रतिऽबोधेन ८. ६, १५; १९. ३५, ३.

प्रतिऽभृतस्य २०. ३२, २.

प्रतिऽमा ८. ९, ६; ९. ४, २.

प्रतिऽमानम् ५. २, ७; २०. ३४, ९; १०७, १०.
प्रतिऽमाम् ३. १०, ३.
प्रतिऽमिताम् ९. ३, १.
प्रतिऽमृशात् ८. ६, १८.
प्रतिऽमोहयन्ती ३. २, ५.
प्रऽतिरन्तः १८. २, २९.
प्रऽतिरन्ते १४. २, ३६.
प्रतिऽवर्तः ८. ५, ४; १६.
प्रतिऽवर्त्म १०. १, ९.
प्रतिऽवेशाः ३. १५, ८; १९. ५५, १; २.
प्रतिऽशत्रवः ४. २२, ६.
प्रतिऽशिक्षन्ति २०. ७६, ५.
प्रतिऽशीवरि १२. १, ३४.
प्रतिऽशृणोति ९. ११, २.
प्रऽतिष्ठन्तीम् १०. ७, २१.
प्रतिऽसरः २. ११, २; ८. ५, १; ४.
प्रतिऽसरेण ४. ४०, १; २; ३; ४; ५; ६; ७; ८.
प्रतिऽसरैः ८. ५, ५; ६.
प्रतिऽस्थया ११. ४, १८.
प्रतिऽस्था १२. १, ६; १९. ६०, २.
प्रतिऽस्थाः १२. ३, २५.
प्रतिऽस्थाम् ६. ३२, ३; ८. ८, २१; ९. ९, १०; १०. २, १; १८. ४, ५; १९. ११, ६.
प्रतिऽस्थाय ११. ४, १८.
प्रतिऽस्थायाः १९. १७, ९.
प्रतिऽस्थायाम् ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
प्रतिऽस्थितः ११. ६, १८; १९. ५२, २.
प्रतिऽस्थितम् १०. ७, १; ३०; ८, ६; ११. ६, १; १५; १७. १, १९[3]; १९. ५३, ९.
प्रतिऽस्थिता १२. ५, ३.
प्रतिऽस्थिताः १०. ७, २२; १९. ५४, ४.
प्रतिस्थे इति प्रतिऽस्थे ४. २६, १; २.
प्रतिऽस्पाशनम् ८. ५, ११.
प्रतिऽहरणेन ५. १४, ८.
प्रतिऽहारः ११. ९, १२.
प्रतिऽहिताभिः १९. १३, ४.
प्रतिऽहिताम् ११. २, १.
प्रतिऽहितायै ६. ९०, ३.
प्रतीचः ३. १, ४; ५. ८, ७; ६. ३२, ३; ७. ११३, २.
प्रतीचः ८. ३, ६.
प्रतीचिका १९. २०, ४.
प्रतीची ३. २७, ३; ७. ३९, ३[3]; ४८, ३; ११३, १; १२. ३, ९.
प्रतीचीः १. २८, २; ८. ५, ५; ६; १०. १, ६.
प्रतीचीनः ९. ३, २२; १०. १, ६.
प्रतीचीनः ४. ३२, ६.
प्रतीचीनऽफलः ४. १९, ७; ७. ६७, १.
प्रतीचीनाय ११. २, ५; ६, ८.
प्रतीचीम् ९. ३, २२; ११. १२, २६; १२. १, ३४; १५. २, १५; १४, ५.
प्रतीच्याः ४. ४०, ३; ५. १०, ३; ९. ३, २७; १२. ३, २४; १५. ४, ७; ९; ५, ६; ७; १८. ३, २७; १९. १७, ५; १८, ५.
प्रतीच्याम् ३. २६, ३; ४. १४, ८; १५. २, १८; १८. ३, ३२.
प्रतीच्यै १२. ३, ५७.
प्रऽतूर्तिषु २०. १०५, १.
प्रऽतोदः १५. २, ७; १४; २०; २७.
प्रत्नः ६. ११०, १.

प्रत्नऽथा २०. ८, १.
प्रत्नम् २०. २४, ९; ३६, ७.
प्रत्नऽवत् २०. ३६, ७.
प्रत्नस्य २०. २६, ३; ९२, १५.
प्रत्नान् ६. १३६, २.
प्रत्नाय २०. ३५, २.
प्रत्नासः १८. ३, २१; २०. ८८, १.
प्रत्नेन २०. ११५, २.
प्रत्यक् ४. १८, २; १९, ५; ६; ४०, १; २; ३; ४; ५; ६; ७; ८; ५. १३, ४; ३०, ५; ८. ३, १४; ५, २; १५; १०. १, ५.
प्रत्यङ् ३. २०, २; ४. ११, ८; १९, ७; ६. ५१, १; ९. १२, २१; ११. १, २२; १३. १, ५६; २, ३; २०[३]; १५. १८, ५; १८. १, २९; १९. ५३, ३; २०. ४७, १७[३].
प्रत्यञ्चः ११. ९, १३.
प्रत्यञ्चम् ७. ४०, २; ८. ३, १७; २५; ११. ३, २९; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १२. २, ५५; २०. ६३, ३; १२४, ६.
प्रत्यञ्चा३म् ११. ३, २६.
प्रऽत्रासम् ५. २१, ३.
प्रऽत्रासेन ५. २१, २.
प्रऽत्वक्षसम् २०. ९४, ३.
प्रऽत्वक्षाणः २०. ९४, १.
प्रथः १३. ९, २.
प्रथताम् ३. २२, १; १२. १, २; ३, ३८.
प्रथते ५. १२, ४.
प्रथमः १. १२, १; २४, १; ४. ६, १[२]; १४, ५; २४, ६; ५. १, २[२]; १७, २; २८, ११; ६. २८, ३; ७. ८७, ४; ५; ९. २, १९; १०. २, ८; ४, १; ६; ८, २८; ११. ७, ९; १३. १, ५५; १४. १, ५५; १५. १५, ३; १६, १; १७, १; १८. १, १९; २७; २८; ३०; ५०; ३, १३[२]; ७३; १९. ४, १; १३, १; २२, २१; २३, ३०; ३२, १०; ५३, २; २०. २५, १; ५; ३४, १; १०४, ४; ११३, २.
प्रथमऽजः ४. ४, ५.
प्रथमऽजम् १. ३५, २.
प्रथमऽजा ८. ९, १६; २१.
प्रथमऽजाः ४. ३५, १; ५. १७, १; ६. १२२, १; ९. १५, १५; १०. ७, १४; १२. १, ६१; २०. ९०, १.
प्रथमऽजाम् २. १, ४; ५, ७.
प्रथमम् ४. १, १; ३, ४; ६, ३; ३९, २; ४; ६; ८; ५. ६, १; ६. ५९, १; ६५, ३; ८. ९, २४; ९. १४, ४; १०. ४, १८; ७, ३१; १२. ३, १; १४. २, ३; १८. २, ५७; १९. ४२, ४; ४६, १; ५२, १; २०. २५, ४; ८८, ४; ९१, २.
प्रथमऽवास्य[म्] २. १३, ५.
प्रथमस्य ४. २१, ५; २३, १; २४, ६; १८. १, ७; १९. २५, १.
प्रथमस्याः ६. १८, १.
प्रथमा १. २४, २; २७, ४; २. २५, २; ३. १०, १; ४; ४. ३०, २; ३२, ७; ५. १२, ७; ६. १०८, १; ७. ८५, ४; ८. ९, ११; ९. ३, २२; १५, २३; १०. ९, १; २०. ८७, ५.
प्रथमाः ४. ७, ७; ५. ६, २; १७, १; ७. ५२, ७; १०. ७, १६; १०, ८; २०. १७, १०; ८९, १०; ९४, ६; १०.
प्रथमाना १२. १, ५५.

प्रथमानाः ११. १, ३२.
प्रथमानि २. ५, ५; ७. ५, १; ९. १५, २५.
प्रथमाम् ६. १८, १; १०८, २; ७. ७८, २; १९. ४. १.
प्रथमाय ४. १, २[२]; ७. १५, ३.
प्रथमे इति १८. १, २९.
प्रथमेन ११. १०, ३३.
प्रथमेभ्यः १९. २२, ८.
प्रथय १२. ३, ३७.
प्रथयंते ६. ७२, १.
प्रथयस्व ६. १०१, १.
प्रथस्व ११. १, १९.
प्रथिना २०. ७१, १.
प्रथिष्ठम् ८. ३, १.
प्रऽदक्षिणम् २. ३६, ६; ७. ५२, ३.
प्रऽदक्षिणित् २०. ८, ३.
प्रऽददातु ८. ४, ९.
प्रऽदुदुषे १२. ४, ३५; ३६.
प्रऽदहन् १०. ८, ३९.
प्रऽदाता ३. २९, ४; ५.
प्रऽदिवः १. १५, १; २०. २१, २.
प्रऽदिवि २०. ६७, ६; ८७, २.
प्रऽदिशः १. ११, २; ३०, ४; २. ६, १; १०, ३; ४; ३. ४, १; २; २०, ९; २२, ५; २४, ३; ४. २, ५; ११, १; १५, १; २०, २; ३५, ५; ५. ३, १; २८, २; ६. ४०, २; ८. ५, ३; ९. २, ११; २१; १५, १९; १०. ६, १९; ७, १६; ३५; ११. २, १०; ७, १२; ८, २२; १२. १, ४; ३१; ५५; ३, ३०; १३. १, ३८; २, ३३; ३४; ३, १; २०; १७. १, १६; १९. १, ३; १०, ८; १४, १; २०, २; ३३, ९; ४९, ३; २०. १०७, १३.
प्रऽदिशम् १२. ३, ७.
प्रऽदिशा ५. १२, ४; ७; ९. १५, १७.
प्रऽदिशि १. ९, २; ४. २३, ७; २८, १; ७. २६, २; २०. ३४, ७.
प्रऽदीध्यतः १०. ४, ११.
प्रऽदीयते १२. ४, ३३; ४०.
प्रऽद्यौः १८. २, ४८.
प्रऽधनेषु १८. २, १७.
प्रऽधयः १०. ८, ४.
प्रऽधावति १८. २, १४.
प्रऽधिः ६. ७०, ३.
प्रऽधौ ६. ७०, ३.
प्रनपादिति प्रऽनपात् २०. ५, ७.
प्रऽनीतये ६. २३, २.
प्रऽनीतीः ७. ११०, १.
प्रऽनीयन्ते ९. ६, ५.
प्रऽनुत्तः ९. २, १४.
प्रऽनुत्तानाम् ११. ११, २०.
प्रऽनृत्यन्तः ८. ६, ११.
प्रऽनेजने १९. २, ४.
प्रऽनेतः ३. १६, ३.
प्रऽनेतारम् २०. ४६, १.
प्रऽनोदम् ६. २८, १.
प्रऽपणः ३. १५, ४.
प्रऽपणम् ३. १५, ५; ६.
प्रऽपतन् ६. ८, २; १९. ५०, ४.
प्रऽपथे ७. १०, १[३]; १८. २, ५५; ३, ४९.
प्रऽपदानि ८. ६, १५.
प्रऽपदाभ्याम् २. ३३, ५; ११. ४, १६[२]; २०. ९६, २१.
प्रऽपदेन ६. ४२, ३.
प्रऽपदोः ६. २४, २.
प्रऽपद्य १४. १, ६४.

प्रऽपद्यन्ते ९. ११, ३.
प्रऽपश्यन् १३. १, ४.
प्रऽपश्यन्तः ५. २, ५; २०. १०७, ८.
प्रऽपा ६. ३०, ६.
प्रऽपितामहान् १८. ४, ३५.
प्रऽपित्वे ३. १६, ४.
प्रऽपिबन्ति १४. १, ४.
प्रऽपीताः ३. १६, ७.
प्रऽपीताम् ६. १०८, २.
प्रऽपीनम् ११. १, ३४.
प्रऽपीनाः १२. ३, ४१; १८. ४, ६.
प्रऽपीनाम् ७. १६, १.
प्रऽपृथक् ६. १२२, ५; १०. ९, २७; ११. १, २७.
प्रऽप्र ७. २७, ३.
प्रऽफर्व्यम् ३. १७, ३; ५. २२, ७.
प्रऽबुधाम् ५. ३, २.
प्रऽब्रुवन् ५. १७, ९.
प्रऽब्रुवाणाः १. ७, ५.
प्रऽब्लीनः ११. ११, १९.
प्रऽभञ्जन् १९. १३, ८.
प्रऽभवन् ३. २९, २.
प्रऽभु २०. ७१, ११.
प्रभुवसो इति प्रभुऽवसो २०. १५, ४; ११७, २.
प्रऽभूः ९. ४, २; १३. ८, २.
प्रऽभृता ५. २, २; २०. १०७, ५.
प्रऽभृतिः २. ३५, ५; १९. ५८, ५.
प्रऽभ्राजमानाम् १०. २, ३२.
प्रऽभ्वीः १२. ३, २७; १८. ३, ६९; ४, २६; ४३.
प्रऽमतिः ७. २१, ५; १८. ३, ६३; २०. १३, ३.
प्रऽमत्या २०. २१, ५.
प्रऽमदा १९. ५६, १.
प्रऽमनाः २. २८, १.
प्रऽमन्दनी ४. ३७, ३.
प्रऽमयुः ८. १, १६.
प्रऽमा १०. ७, ३२.
प्रऽमार्दम् २०. १८, ३.
प्रऽमारेण ११. १०, ३३.
प्रऽमिनाम १९. ५९, २.
प्रऽमीलिनम् ८. ६, २.
प्रऽमुञ्चन् ७. ८९, १.
प्रऽमुञ्चन्तः २. ३४, २.
प्रऽमुदः ११. ९, २६; १०, २४; १८. १, १३.
प्रऽमूर्णम् १२. १०, १५.
प्रऽमृणन् ३. १, ४; ५, १; ४. ३१, ३; ५. २३, ६; ११. २, २३; १६. १, २; १९. १३, ८; ६६, १.
प्रऽमृणन्तम् ६. ९७, ३; १९. १३, ६.
प्रऽमृशन्तम् ८. ६, ६.
प्रऽमोतम् ९. १३, ४.
प्रऽमोदन्ते ४. ३८, ४.
प्रऽमोदिनीम् ४. ३८, ४.
प्रयः २०. ३५, १.
प्रयःऽइव २०. ३५, २.
प्रऽयक्षु ५. २७, ५; ६.
प्रऽयच्छन्तः ६. १२२, २.
प्रऽयच्छन्ति १०. ७, ३९.
प्रऽयच्छसि २०. ५, ४.
प्रयज्यो इति प्रऽयज्यो २०. ३६, ११.
प्रऽयतः १३. २, ३१.
प्रऽयतस्य २०. ८७, ६.
प्रऽयता १८. ३, ४२; ४, ६५; २०. १०३, २.
प्रऽयतानि १८. ३, ४४.

प्रऽयताम् ५. २०, ९.
प्रऽयति ७. १०२, १; २०. ११८, ३.
प्रऽयतिम् २०. ९२, १९.
प्रऽयती १४. १, १२.
प्रऽयन् ६. ३१, १; २०. ४८, ४.
प्रऽयन्ता २०. ३७, १.
प्रऽयस्ता १२. ८, ४.
प्रऽयस्यन्ती १२. ८, ४.
प्रयस्वान् २०. ८९, ९.
प्रऽयाजाः १. ३०, ४.
प्रऽयुजः ११. १०, २९; २०. ३२, २.
प्रऽयै २०. २९, ७; ३३, २.
प्रऽरुहः १३. १, ८; ९.
प्रऽलयनम् १. २३, ३.
प्रऽलापाः ११. १०, २९.
प्रवणे २०. १९, १; १७, ३.
प्रऽवतः १. १३, ३.
प्रऽवतः ४. २९, ६; १०. १०, २; ३; १२. १, २; १३. २, २८; ३३; १८. १, ४९; ४, ७; २०. ७९, २.
प्रऽवतः १. १३, २; २६, ३.
प्रऽवतम् ६. २८, ३.
प्रऽवता ३. १, ४.
प्रऽवदः ५. २०, ९.
प्रऽवदन्ति ४. २४, ३.
प्रऽवन्तवे २०. ७९, ३.
प्रऽवतौ १५. २, ५; १३; १९; २९.
प्रऽवसन् ७. ६२, ३.
प्रऽवहन्ति ६. ९१, २.
प्रऽवाति १०. ८, ३९.
प्रऽवाम् १२. १, ५१.
प्रऽवाय्यम् ६. १०९, १.

प्रऽविद्वान् ५. २६, १; ३; ९; ७. १०२, १; ११. १, ३१; १२. २, ५९.
प्रऽविध्यन्तः ३. २६, ४.
प्रऽविवेश १२. २, ४; ७.
प्रविशिऽवांसम् ४. २३, १.
प्रऽविश्य १. २९, १; १२. ९, ३.
प्रऽविष्टः ४. ३९, ९; १०. ८, २८; ४०; १४. २, ५१; ५८.
प्रऽविष्टम् १४. २, ५३; ५४; ५६; ५७.
प्रऽविष्टा ३. १०, ४; ६. ७३, २; ८. ९, ११.
प्रऽविष्टाः ७. ८१, ४; १०. ८, ४०; १८. २, २८.
प्रऽविष्टाम् १२. १, ६०; १९. ४, २.
प्रऽवीयमाना १२. ४, ३७.
प्रऽवीरः १९. १३, ९.
प्रऽवृद्ध २०. ११२, २.
प्रवृद्धे इति प्रऽवृद्धे ४. २६, २.
प्रवेदऽकृत् ५. २०, ९.
प्रऽव्यथिताः १०. ३, ९.
प्रऽशर्ध २०. १२०, १.
प्रऽशस्तम् २०. ९६, ३.
प्रशस्तिऽभिः १. ४, ४.
प्रऽशस्तिम् २०. ११७, ३.
प्रऽशिषः ११. १०, २७.
प्रऽशिषम् ४. २, १; १३. ३, २४; ६, ६.
प्रऽशिषा ६. १३३, १; १४. १, ५३.
प्रऽशिषि ५. १२, ११.
प्रऽशिष्टाः १२. ३, २७.
प्रऽशृणाति ७. ८०, ३.
प्रष्टयः १०. ८, ८.
प्रष्टिः १३. १, २१.
प्रष्ठम् ९. १४, ४.
प्रऽसक्तः ७. ५२, ३.

प्रऽसर्पतः ८. ६, २२.
प्रऽसर्पसि ४. ९, ४.
प्रऽसर्स्रीणम् ६. ३९, १.
प्रऽसवानाम् ५. २४, १.
प्रऽसवे ३. २०, ८; ६. ९२, १; ७. ७, २; ८. ९, ८; १९. ५१, २.
प्रऽसाधनः १३. १, ६०.
प्रऽसितयः २०. ५९, ४.
प्रऽसितिम् ८. ३, ११; १४; १४. १, ४६.
प्रऽसितौ ८. ४, १३.
प्रऽसूः ३. २३, ४.
प्रऽसूतः ३. १, ४; ६. ६३, १; १९. ५१, २.
प्रऽसूताः १२. १, ६२.
प्रसूऽमतीः ८. ७, २७.
प्रस्कण्वम् २०. ९, ३; ४९, ६.
प्रऽस्तरः १६. २, ६.
प्रऽस्तरम् १८. १, ६०.
प्रऽस्तराय १६. २, ६.
प्रऽस्तुतम् ११. ९, ५.
प्रऽस्तृणतीः ८. ७, ४.
प्रस्थाऽवत् ३. १७, ३.
प्रऽस्थितम् २०. ६७, ५; ७.
प्रऽस्थितान् २०. ८७, २.
प्रऽस्रपिताम् १०. १, १०.
प्रऽस्रवणेषु २०. ५२, १; ५७, १४.
प्रऽस्वाः १९. १०, ७.
प्रऽहरन्तः १९. ४६, ३.
प्रऽहरसि ७. ५८, ८.
प्रऽहरेम १४. २, ३८.
प्रऽहाम् ४. ३८, ३; ७. ५२, ६; २०. ८९, ९.
प्रऽहाय्याः १५. ३, १०.
प्रऽहासिनः ८. ६, १४.
प्रऽहितः २. २९, ४; १८. ४, ६५.
प्रऽहितान् ८. २, ११.
प्रऽहितौ ६. २९, २.
प्रऽहुतः ४. १२, ७.
प्रऽहेतारम् २०. १०५, ३.
प्रऽहेया ५. १७, ३.
प्राः २०. ८०, १.
प्राक् २०. ९४, ७; १२०, १.
प्राक्तः ८. ४, १९; १८. ३, ३.
प्राघर्मऽसत् २०. ९०, १.
प्राङ् ३. ४, १; ९. १२, २०; १९, १६; १०. ८, १०; १३. २, ३; १५. १८, ९.
प्राचः २०. १२९, १.
प्राची ३. २७, १.
प्राचीः ५. २८, ११; १२. १, ३१; २०. १३७, १.
प्राचीनऽउपवीतः ९. १, २४.
प्राचीनऽपक्षा ३. २९, ३.
प्राचीनम् ४. ११, ८; ५. १२, ४; ७.
प्राचीम् ७. १८, २; १५. २, १; १४, १.
प्राचीम्ऽप्राचीम् १२. ३, ७.
प्राचैः २०. २५, २.
प्राच्यम् ४. ७, २.
प्राच्याः ४. ४०, १; ५. १०, १; ६. ९८, ३; ९. ३, २५; १५. ४, १; ३; ५, १; २; १८. ३, २५; १९. १८, १.
प्राच्याम् ३. २६, १; ४. १४, ७; १५. २, ४; १८. ३, ३०.
प्राच्याम् ५. ४, ८.
प्राच्यै १२. ३, ५५.
प्राजाऽपत्यः ९. ७, ११.
प्राजाऽपत्यम् ३. २३, ५; १८. ४, १२; १३.
प्राजाऽपत्याः ११. ७, २२.
प्राजाऽपत्याभ्याम् १९. २३, २६.

प्राश्वः ११. ८, १८; १२. २, २२; १३. ४, ७; १५. ३, ६.
प्राश्वम् ८. ३, ९.
प्राणं ११. ६, २६[२]; १९. ४४, ४.
प्राण २. १५, १; २; ३; ४; ५; ६; ११. ६, २[३]; ७; ८; ९[२]; १४; १६; १८; १९; २३.
प्राणः २. २८, ३; ५. ९, ७; ३०, १३; १५; ६. ५३, २; ७. ३२, १; ५५, ३; ४; ८. १, ३; १५; ९. १, २; ४; २, ५; १६; ५, २१; १०. २, २७; ३०; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ११. ५, ७; ६, ३; ४; ५; १०[२]; ११[३]; १२[३]; १३[२]; १५; १७; २४; ११, २१; १२. ६, ३; १३. १, १७; १८; १९; १५. १५, ३; ४; ५; ६; ७; ८; ९; १६. ४, ३; ७, १३; १८. २, २६; ४६; ४, ५८; १९. ४४, ५; ५१, १; ५३, ७; ५८, १; २; ६०, १.
प्राणत् १०. ८, २; ६; ११; ११. २, १०; १२. १, ३; ४.
प्राणतः ४. २, २.
प्राणताम् ३. ३१, ९.
प्राणति ४. ३०, ४; ११. ६, १०; ९, २३; १३. ४, ११; ५, ६.
प्राणतीनाम् ८. ९, ९.
प्राणते ११. ६, ८.
प्राणदः ४. ३५, ५.
प्राणदऽवान् ४. ३५, ५.
प्राणन्ति १. ३२, १; १०. १०, ५; १३. ३, ३.
प्राणम् २. ३४, ५; ४. ५, ४; १५, १०; ५. ८, ४; ७. ५५, ६; ८. २, ३; १३; ९. ७, २; १०. २, १३; २९; ५, ३५; ३६; ११. ५, ५; ६; ६, ११; १२[२]; १५; १०, ३१; १२. १, २२; १३. ३, ५; १५. ११, ५; १४, २१; १६. ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; १९. २७, ५; ६; ४४, ४; ४६, ३; ५८, २; ६३, १; ७१, १.
प्राणयति १३. ३, ३.
प्राणऽसंशितः १०. ५, ३५.
प्राणस्य ५. ३०, १०.
प्राणाः ६. १०४, १; ८. १, १; ११. ३, २८; १५. १५, २; १७. १, ३०; १९. ४६, ५.
प्राणात् ६. ३१, २; १०. ५, ३५; १९. ६, ७; २०. ४८, ५.
प्राणान् २. १२, ७; ३. ३१, ६; ५. २८, १; ६. १३५, २; ३; ११. ७, २२; १२. ७, १६; १९. ४३, २.
प्राणापानाः ११. ३, २; ४, ७.
प्राणापानान् ११. ११, ११.
प्राणापानाभ्याम् २. २८, ४.
प्राणापानैः ११. ४, ७[२]; १२. ३, २८.
प्राणापानौ २. १६, १; १६. ४, ५.
प्राणापानौ ५. १०, ८; ७. ५५, २; ८. २, ११; १०. ७, ३४; ११. ६, १३; ७, २४; ९, २५; १०, ४; २६; १६. ४, ७.
प्राणापानौ ३. ११, ५; ६; ७. ५५, ५.
प्राणाय ५. ४, ७; ६. १०, २; ४१, २; ८. २, ४; ११. २, ३; ६, १; १९. ४५, ६; ७; ८; ९; १०.
प्राणाहस्य ९. ३, ४.
प्राणे ९. ७, ५; १०. ५, ४४; ११. ६, १५[२].

प्राणेन॑ ३. १३, ५; २९, ८; ३१, ६; ७; ८; ९; ५. ३०, १४; ६. ६२, १; ७. ८६, ५; ८. २, ४; ९, ९; १०. ८, १९; ११. ६, ६; ९, २३; १३. ३, ४; १५. १४, २२; १९. २७, २; ७[३]; ८.
प्राणेषु॑ ३. १५, ७.
प्रातः ३. १६, १[६]; ४. ११, १२; ६. १०८, ५; १२८, २; ७. १०६, १; ९. ३, १८; ११. २, १६; १३. ३, १३; २०. २३, २; ३५, १६; ८९, ५.
प्रातःऽजित॑म् ३. १६, २.
प्रातःऽप्रा॑तः १९. ५५, ३; ४.
प्रातःऽसवने ६. ४७, १; ९. १, ११.
प्रादुः ९. १, २४.
प्राय॑श्चित्तिम् १४. १, ३०.
प्रावृ॑ता १२. ५, २; १८. ३, ३.
प्रावृषा॑ १९. ६, ११.
प्रावृषि॑ १२. १, ४६.
प्राश॑म् २. २७, १[२]; २; ३; ४; ५; ६; ७.
प्राशि २. २७, ७.
प्राह्रा॑दिः ८. १३, २.
प्रियऽअप्रियाणि॑ १०. २, ९.
प्रियः २. ३६, ४; ४. २२, ४[२]; ३७, ११; ६. ५८, १; १३०, २; ८. १०, ५; ९. १, ११; १२; १३; ९, १०; १५. ११, ७; १५, ८; १७. १, २; ३; ४; ५; १८. ३, ७; ५३; १९. ४५, २; २०. ६४, १.
प्रियत॑नोःऽइव ५. १८, ६.
प्रियऽत॑मः ५. ३०, १७.
प्रियऽत॑मम् ५. २८, ६.
प्रियऽत॑मा १४. २, ५०.
प्रियत॑मे इति॑ प्रियऽत॑मे ७. १०, १.
प्रियऽधा॑मा १७. १, १०.
प्रियम् २. २८, ५; ३४, २; ३. ५, ३; ४. ३१, ५; ६. ३७, २; ७. १५, १; ३०, २; ३३, १; ९. २, २; ११. ६, १०; १२. १, ७; २, ३४[२]; ३, ३२; ४९; ४, ४०[२]; १४. १, २१; १५. २, ४; १२; १८; २४; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ८, ३; ९, ३; ११, २; ६[२]; ७; १९. ३२, ८; ६२, १[३]; २०. ३२, १; १२६, ४; १२; १३.
प्रिय॑ऽमेधासः २०. ९२, ५.
प्रियऽमे॑धासः २०. १०, २; ५९, २; ९२, १५.
प्रियऽयमा॑णाः १९. २७, १०.
प्रियऽव॑ते ४. १८, ४.
प्रियऽवादिनी॑ ३. २५, ४.
प्रियस्य॑ १५. ११, ७.
प्रिया १०. ८, २५; ११. ६, ९; १२, ५; १५; १२. ३, १; २०. १२६, ५.
प्रियाः ७. ६३, १; ९. ५, ३०; ७, ६; १४. २, ५; २०. ८, ३; ६७, ४; १०९, २.
प्रियाणा॑म् १२. ३, ४९.
प्रियाणि॑ १३. १, ११.
प्रियान् १८. ४, ६१.
प्रियाम् ४. १८, ४; १८. ३, ४१.
प्रियास॑ः २०. ३४, १८; ३७, ७; ८.
प्रियासम् ३. ५, ४.
प्रिये १२. १, ५२.
प्रियेषु॑ १८. ३, ४५.
प्रीताः १०. ९, ४.
प्रुष्णुते २०. ७३, ५.
प्रुष्वा १८. ३, ६०.
प्रेण्यः ६. ८९, १.
प्रेप्सन्ती॑ इति॑ प्रऽईप्सन्ती॑ १०. ७, ६.

प्रेयसी ११. ६, ९.
प्रैणानः ५. २७, ३.
प्रो इति ७. ११९, २; २०. ९५, २.
प्रोष्ठऽपदा १९. ७, ५.
प्रोष्ठेऽशयाः ४. ५, ३.
प्लक्षात् ५. ५, ५.
प्लवन्ताम् ३. ६, ७; ९. २, १२.
प्लवम् १२. २, ४८.
प्लवस्व ४. १५, १४.
प्लाशयः ९. १२, १२.
प्लाशिः १०. ९, १७.
प्लाशेः २. ३३, ४; २०. ९६, २०.
प्लीहानम् ३. २५, ३.
प्लीह्नः २. ३३, ३; २०. ९६, १९.
प्सातः १०. ३, १४.
प्सातु १०. ५, ४३.
प्साहि १०. ३, १४.

फ

फट् ४. १८, ३.
फलम् ६. १२४, २.
फलऽवतीम् ७. ५२, ९; १९. ३१, ३.
फलिऽगम् २०. ८८, ५.
फलिनम् ३. १९, ४.
फलिनीः ८. ७, २७.
फलीऽकरणाः ११. ३, ६.
फल्गुनीषु १४. १, १३.
फल्गुन्यौ १९. ७, ३.
फालम् १०. ६, ६; ७; ८; ९; १०.
फालात् १०. ६, २.
फालेन १०. ६, ३३.
फेनम् १२. ३, २९.
फेनम्ऽइव १. ८, १.
फेनान् ६. ११३, २.

फेनेन २०. २९, ३.

ब

बजः ८. ६, ६; ७; २४.
बजम् ८. ६, ३.
बट् १३. २, २९[२]; २०. ५८, ३[२]; ४.
बण्डया १२. ४, ३.
बण्डेन ७. ६७, ३.
बत १८. १, १५.
बतः १८. १, १५.
बद्धः २. १२, २; ३५, ३; ६. १११, १.
बद्धकम् ६. १२१, ४.
बद्धकऽमोचनम् ६. १२१, ३.
बद्धम् ७. १३, ४; ४३, २.
बद्धा ५. ३०, १६.
बद्धानाम् ६. ८४, १.
बद्धानि १३. ७, १७.
बद्ध्वा ८. ८, १०; १०. ६, १८.
बद्ध्वाऽइव ७. ३९, ५.
बधान १०. ५, ४४.
बधिरः ११. ४, २.
बधिराः ११. ११, २२.
बध्नन्ति ३. ९, ३.
बध्नन्तु ८. ५, १०.
बध्नात् ६. ८१, ३; १९. ४६, १.
बध्नातु ८. ५, २२.
बध्नामि ११. ६, २६.
बध्नामि १. ३५, १; ३. ९, ८; ४. १०, ७; ५. ३०, १; १९. २८, १; ३२, १; ३३, ४; ४६, १.
बध्नीमः ४. ३८, ७.
बध्यताम् १. १४, २; २९, ४; १२. ४, ३७.
बध्यते ९. ६, ६; १८. ४, ७०.
बध्यते ८. ५, १; १४. १, २६; १९. ३१, १४; ४५, ४.

वध्यन्ताम् ३. १७, ६.
वध्यमानम् २. ३४, ३.
वध्यसे ६. १२१, २[२].
वध्यासम् ७. ५२, १.
वध्वै १३. ७, १७.
वन्धः १०. ९, ४४; १९. ५६, २.
वन्धनम् ६. १४, २.
वन्धनात् ३. ६, ७; ९. २, १२; १४. १, १७.
वन्धऽपाशान् ६. ६३, २; ८४, ३.
वन्धम्ऽइव ५. १४, १०.
वन्धात् ६. १२१, ४.
वन्धु ५. १३, ७; २२, ८; १०. १, ३.
वन्धुः २. १, ३; ४. १, ३; ५. ११, १०; ११; ९. १५, १२; १०. १०, २३.
वन्धुना १९. ५६, ५.
वन्धुरः ३. ९, २.
वन्धुरम् १०. ४, २.
वन्धुरा ३. ९, ४.
वन्धेभ्यः १९. ४५, ५.
वन्धेषु १४. १, २६.
ववर्ह ९. ३, ३.
ववाधे ९. २, १८.
ववाधे २०. १६, ९.
वभस्ति ९. २, २.
वभस्ति ६. ४९, १; २.
वभाज ९. १४, ८.
वभूथ ११. २, २८; २०. ६४, २.
वभूथ १८. ३, २.
वभूव २. ३६, ४; ३. २२, ६; २३, ६; ४. २, ३; १५, १०; ३५, ५; ६; ६. १३३, ४; ७. २१, ५; ८. ७, २; ९. ४, २; १०. २, ३; १२. ३, ३१; १३. १, २५; २, ४४; ३, ७; १९. ४६, ४; २०. ३४, ९; ७७, ५.
वभूव ३. २८, १; ४. ८, १; १०, ७; ३०, ८; ५. ५, ७; २८, ६; ७. ५, २[३]; २१, ६; ८. ७, १२; ९. १५, २४; १०. ७, ८; ८, ७; ३०; ३६; १२. ३, १०; ५०; ५१; १३. २, २५; १९. ३२, १०.
वभूवथुः ४. २५, १; १९. ५८, ३.
वभूवाँ३ १०. २, २८.
वभूविथ १. ७, १; ३. २३, १; २०. १०८, २.
वभूविथ ९. ५, ६; १२. १, १८; १९. ५६, १; २.
वभूविम ३. २०, ८.
वभूवुः ९. २, २२; १०. ८, ९.
वभूवुषी ९. १५, २१; १३. १, ४२.
वभ्रवः ८. ७, १.
वभ्रवे ६. २०, ३; ५६, २; ७. ११४, १.
वभ्रु ६. १३९, ३.
वभ्रुः ५. २३, ४; ६. १६, ३; ९३, १; ११. ७, २६.
वभ्रुऽकर्णः ५. २३, ४; ६. १६, ३.
वभ्रुणा ४. २९, २; ५. ७, ५.
वभ्रुम् १२. १, ११.
वभ्रून् ७. ११४, ७.
वभ्रे ११. १, ३२.
वभ्रेः ११. १, ३१.
वभ्रो इति ५. १३, ५.
वभ्रोः २. ८, ३; ५. १३, ६.
वर्जह्यो३ इति ११. १०, १४.
वर्वृहि १८. १, ११.
वर्हणाः २०. ११, ५.
वर्हयः २०. २१, ६.

बर्हिः ५. १२, ४; ८; २२, १; २७, ९; ७. १०३, १; ८. १, १६; ९. ४, १०; ६, ८; १०. ९, २; १२. ३, ३२; ३३; १८. ४, ५१; ५२; ६८; २०. ३, १; १३, २; २३, २; ३; ९; २५, ६; ३८, १; ४७, ७; ६७, ४; १०३, २.
बर्हिःऽस्थाम् २०. २४, २.
बर्हिषः २०. ६१, २; १२५, २.
बर्हिषा ५. २६, ६.
बर्हिषि ७. ६०, २; १०. १; १८; १०, १२; १७; १८. १, ४२; ५९; ३, २०; ४४; ४, ४६; २०. ५, ५; १७, २; २२, ५; ९२, २; ९४, ५.
बर्हिष्मते २०. २१, ६.
बर्हिष्येषु १८. ३, ४५.
बर्हिऽसदः १८. १, ५१.
बर्हिऽसदः १८. १, ४५.
बलऽदाः ४. २, १; १३. ३, २४.
बलऽदावा ४. ३२, ५.
बलम् १. ३५, ३; २. १७, ३[२]; २६, ४; ३. १९, १; २; ४. २४, २; ५. ९, ८; ३०, १३; ६. ६, ३; १२६, २; १३५, १; ७. ५७, १; ५८, ६; ८. १, १५; ७, ५; २२; ९. १, १७; १२, ९; १०. २, १५; ५, १; २; ३; ४; ५; ६; ६, ७; १०, २०; ११. ९, १७; १०, २०; १२. १, ८; ६, १; १५. १४, ३; १८. ४, ५३; १९. ३३, ४; ३७, १; २; ४१, १; ४३, ६; ४६, ३; ६०, १.
बलम् ४. २३, ५; ९. ३, २; १९. २८, ३.
बलवत्ऽतमः ५. ४, १.
बलवत्ऽतमाम् ३. १८, १.
बलऽवान् ६. ९२, २.
बलऽविज्ञायः १९. १३, ५.
बला १. १, १.
बलात् २०. ९३, ५.
बलाय १. ३५, १; ३. १९, ३; ४. १०, ७; ६. ६३, १; ११. १२, ११; १९. २६, ३; ३७, ३; ४६, १.
बलास ६. १४, ३; १२७, २.
बलासः ४. ९, ८; ९. १३, १०.
बलासऽनाशनीः ८. ७, १०.
बलासम् ५. २२, ११; ६. १४, १; २; ९. १३, ८; १९. ३४, १०.
बलासस्य ६. १२७, १.
बलासिनः ६. १४, २.
बलासेन ५. २२, १२.
बलिः ११. १२, ५.
बलिनः १४. १, २.
बलिना ६. ११७, १.
बलिम् ३. ४, ३; १०. ७, ३९; ८, १५; ११. ६, १८; १९; १९. ४५, ४; ५५, ६.
बलिऽहाराय ११. १, २०.
बलिऽहृतः ११. १, ६; ६, १९; १२. १, ६२.
बली ३. ५, १.
बलीयसे ३. २९, ३.
बले २. २९, १; ११. ९, १७.
बलेन ३. ५, १; ४. २५, ४; ५. ३०, १४; ६. ९२, २; ७. ८७, २; ९. २, ६; १३. १, ६; १५. १४, ४; १८. २, ५९; ६०.
बल्बजम् १४. २, २२; २३.
बल्हिकान् ५. २२, ७; ९.
बल्हिकेषु ५. २२, ५.
बष्कयै ९. १४, ६.
बस्तऽअभिवासिनः ११. ११, २२.
बस्तऽवासिनः ८. ६, १२.

वस्तिना ११. ४, १२[२].
वस्तौ १. ३, ६.
वह्वः १. २७, ३; २. १३, ५; ३. १५, २; ६. ५५, १; १२. १, ४७; २, २१; १३. ३, १७; १८. ३, ६१.
वहिः १. ३, १; २; ३; ४; ५; ६; ७; ८; ९; ९. १३, १; २; ३; ४; ५; ६; ७; ८; ९; ११; १३; १४; १५; १६; १७; १८; १९. ४४, २.
वर्हिष्ठः ४. ३४, ५.
वहु १. १०, ३; ३. ५, ४; २४, २; ४. २८, ४; ३४, २; ५. २१, ५; ६. १४१, २; ८. ८, २०; १०. ८, २२; ११. ७, २६; १२, ४; १२. १, २; १८. १, १२; १९. ४४, ८; ६०, १.
वहुः ६. १४२, १; ७. ६२, ३.
वहुऽचारी ११. ४, १५.
वहुऽधा १. ३३, ३; २. ३४, ४; ३. ४, ७; ४. १५, १६; २३, १; ५. २०, ४; ९; २६, ७; ८; १०; ११; ६. ७१, १; ९. १, ३; ५, १; ३; १५, २८; १०. ४, २३; ८, १३; ११. २, १७; १२. १, ४; ४४; ४५; ३, २१; ५४; ४, २९; १३. ३, १७; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १८. २, ५७; १९. ५३, ३.
वहुधा २०. ९६, २४.
वहुऽप्रजाः ९. १५, १०.
वहुऽभिः ४. १, ६; ७. २७, ८.
वहुऽभ्यः ५. २०, ९; ६. २८, ३; १८. १, ४९; २०. ६३, ६.
वहुम् ३. ४, ३; २४, ७; ६. ५, १.
वहुलऽअन्तासः २०. ८९, ८.
वहुलम् ४. १५, ६; ८. ५, १९; १२. ३, ८; २०. ८९, ५.
वहुला १०. २, ९; १९. ५८, ४.
वहुलाः ३. १४, ६; ४. १८, ३; ३८, ६.
वहुलान् ११. १, १७; १२. ३, २९.
वहुलानि १९. २०, २.
वहुलाभिः ७. ३२, १.
वहुले ७. ५४, २.
वहुऽसूवरी ७. ४८, २.
वहून् १९. ३२, ६.
वहूनाम् ४. ३१, ४.
वह्वीः ६. ९६, १; ११. ६, ३; १३. २, ४; ६; ७.
बार्णः ६. १०५, २.
बार्णःऽइव ३. २३, २.
बाणम् १०. २, १७.
बार्धः २०. ४३, १.
बार्धताम् ७. ९६, १; २०. १२५, ६.
बाधताम् ५. २२, १; १०. ३, ११; २०. ९६, ११.
बार्धते ३. १८, १.
बाधते १. १६, ३; २. ४, ३; ८. ५, ७; १९. ३६, २.
बाधथाः १८. ३, ५०.
बार्धमानः ६. १२६, २; ९. ५, १८; १७. १, १७.
बाधय १२. १, ४९.
बाधसे ४. ९, ४.
बार्धस्व ८. ६, २५.
बाधस्व ४. २२, ७; २०. ८९, ७; ९३, २.
बाधामहे ५. ३, १०.
बाधिष्ठ १८. २, २५; २०. १२, ३.
बार्धे २०. ३५, २.

बाधे ४. ३५, ७; ५. १३, ३.
बाधेते इति ८. २, १८.
बाधेथाम् ६. ९७, २; ७. ४३, १.
बार्हतैः १४. १, ९.
बार्हत्ऽसामे ५. २९, ९.
बार्हस्पत्यः ९. ४, १.
बाल् १. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १८. २, २२.
बालाः ९. १२, ८; १०. ९, ३; २२.
बालात् १०. ८, २५.
बालान् १२. ४, ७.
बालेभ्यः १०. १०, १.
बाहवः ३. १९, ७; ११. ११, १; १३.
बाहुऽअङ्कैः ११. ११, १२.
बाहुऽओजसा २०. ७, २.
बाहुऽच्युता १८. ३, २५; २६; २७; २८; ३०; ३१; ३२; ३३; ३४; ३५.
बाहुऽभिः २०. १३, २; ८७, ४.
बाहुऽभ्याम् २. ३३, २; १३. २, २६; १९. ५१, २; २०. ९६, १८; ११७, १.
बाहुम् १८. १, ११.
बाहुऽमान् १. ७, ४; १३. १, ३०.
बाहुऽवीर्यैः ५. २१, १०.
बाहुऽशर्धी १९. १३, ४.
बाहू इति ४. २, ५; ६. ६५, १; ९९, २; ३; ७. ७३, ४; ५; ९. ४, ८; १२, ७; १०. २, ५; ९, १९; १९. ६, ५; ६; १३, १; १५, ४.
बाहून् ३. १९, २; ६. ६५, २; ८. ३, ६; ११. १२, १६.
बाहौ २. २७, ३.
बाह्यम् २. ३०, ४[२].
बाह्याः १९. ४४, ६.

बाह्वोः ७. ५८, ६; १९. ६०, १; २०. ६७, ६; ९३, ७.
बिन्दुः ९. १, २१; १०. १०, १९; १९. ३०; ५.
बिन्दून् १२. ३, २९.
बिभरत् १. ३५, ३.
बिभर्ति १. ३५, २; ४. ९, ५; ८. ५, १२; १३; ९. १४, ४; ११. ९, १५; १२. १, २; ४; १९. ५३, ९.
बिभर्ति १९. २६, १; २.
बिभर्ति ९. २, १५; ४, ३; ७; ११. ७, ३; २४; १८. ४, ३५[२].
बिभर्तु १३. १, १.
बिभर्मि ४. ३०, १; ६; १०. ३, १२; २०. ९४, ९.
बिभर्षि ४. ३१, ६; ७. ४४, १; ५८, ६; ९. ४, ६; ११. २, १२; १२. १, १५; १९. ४९, ८; २०. ९३, ७.
बिभाय ५. ११, ४; १०. ८, ४४; १४. २, ५०.
बिभिदुः २०. ७७, ६.
बिभिदुः १०. ६, २०.
बिभीत ७. ६२, १.
बिभीतः २. १५, १; २; ३; ४; ५; ६.
बिभीतन ७. ६२, ४; ६; १८. ३, ६४.
बिभृथः ४. २६, ४[२]; ५.
बिभृमः २. ४, १.
बिभृहि १८. ४, ५६.
बिभेः २. १५, १; २; ३; ४; ५; ६; ५. ३०, ८; ८. २, २३; २४.
बिभेद २. ५, ३; २०. ७, २; ११, १०.
बिभेद १०. ४, ५; २०. १६, ४; १०७, ३.
बिभ्यतः ५. २१, २.

बिभ्यंताम् ८. ८, २०.
बिभ्यंतीः ५. २१, ९.
बिभ्रंत् ५. २८, १०; ७. ६२, १; ८. ५, १४; ९. ४, १; १४, १०; १०. ६, १०; १३; १२. २, ४९[२]; १९. ३१, ४; ३३, ९.
बिभ्रंतः १. १, १; ४. १४, २; ७. ३३, १; ८. ६, १४; १०. ६, १६; २०. ९१, १०.
बिभ्रंतम् १४. २, ३०; १९. ३२, ९.
बिभ्रंति ८. ६, ११; १३; १२. १, २३.
बिभ्रति ३. १३, ५; ११. ७, २२; १२. १, १९.
बिभ्रंती १. २७, २; ४. ३८, ४; ९. ३, १६; १४, १७; १०. १०, १४; १५; १२. १, ६; ४४; ४५; ४८; १३. १, ४१; १४. २, १४.
बिभ्रंतीः ३. १४, ३; १०. ६, १४.
बिभ्रंतीम् १२. १, २९.
बिलंम् ७. ३६, २; ९. १३, ११; १३; १४; १५; १६; १७; १८; १९. ६८, १.
बिलें १२. ३, १३.
विष्कले १. ११, ३.
बिसंम् ५. १७, १६.
बीजंम् ३. १७, २; १०. ६, ३३; १४. २, १४; ३८.
बीजांनि ३. २३, ४.
बीभत्सुः ९. १४, ८.
बीभत्सौ ११. १०, २८.
बुद्बुदऽयांशवः २०. १३७, १.
बुध्ने २. १४, ४; १२. ३, ३०.
बुध्न्यः १९. ११, ३.
बुध्न्याः ४. १, १; ५. ६, १.
बुध्यात् ४. १, ५.
बुध्यते ९. १, २४.
बुध्यंमाना १४. २, ३१; ७५.
बुध्यंमानौ १४. २, ४३.
बुध्यस्व ९. १, २४; १४. २, ७५.
बुध्येम १९. ६७, ३.
बृहत् ३. ८, १; २२, १; ४; ४. २१, ६; ३४, १; ६. १, १; ३३, १; ५५, ३; ८. ५, १९; ८, ६; ७; ९, ४; ११, ६; ९; ११. ३, १६; ७, १२; १०, २०; १२. १, १; १३. ३, ११; १२; १५. २, २; ३, ५; ४, २; ३; १८. १, ७; २, ६; ३, २४; ७३; २०. २०, ३; ३१, ५; ३८, ४; ४७, ४; ५७, ६; ६१, ५; ६२, ५; ९; ७०, ७; ७१, १३; १४; १६; १०२, ३; १०६, १; १४२, २.
बृहतः ६. १२४, १; ८. ८, ६; ७; ९, ४; १५. २, ४; १९. ६, १६.
बृहतम् ११. ११, ११.
बृहत्ऽअर्काम् ८. ९, १४.
बृहता ५. १०, ८; ८. ३, २४; ११, ७; १३. २, ९; १८. ३, ६५; १९. ५२, १.
बृहताम् ७. ८, १.
बृहती १. १७, ४; ४. १६, ३; ८. ९, ४; ५; ९. १, ८; २, १५; १३. १, १५; २२; १९. २१, १; ४७, १; २०. १५, ५.
बृहती इति ५. १२, ६; १९. १०, ३.
बृहतीः ९. १२, ५; १३. २, ८; ४२; २०. ११९, १.
बृहतीः ५. १२, ५.
बृहतीम् ३. ३, २; १५. ६, १०; २०. ३६, १०; ९१, १.
बृहते २. ४, १; १४. २, ३०; ७२; १५. २, ३; १९. ११, ६; ६४, १; २०. ११, ४; १५, १; ६२, ५; ७१, १६.

वृहत्ऽगावा १९. ५६, ३.
वृहत्ऽछन्दाः ३. १२, ३.
वृहत्ऽजालेन ८. ८, ४.
वृहत्ऽदिवः ५. २, ८; ९; २०. १०७, ११; १२.
वृहत्ऽपलाशे ६. ३०, ३.
वृहत्याः ८. ९, ४.
वृहत्ऽरये २०. १५, १.
वृहत्ऽसामानम् ५. १९, २.
वृहन् ४. १६, १; ६. ५३, १; ८२, ३; ९. ४, ५; १०. ८, ३; ४०; २०. १०६, ३.
वृहन्तः १०. ७, २५.
वृहन्तम् ४. १४, ६; ६. १२२, ४; ७. ४०, १; २०. १४३, ६.
वृहन्ता १९. १५, ४.
वृहन्ति ८. ९, ३.
वृहस्पतये २. ३५, ४; १२. ३, ६०.
वृहस्पतिः २. १३, २; २६, २; २९, १; ३. ११, ४; ८; १२, ४; १४, २; २०, ३; २६, ६; २७, ६; ४. १, ५; ५. १७, ५; २५, ४; २८, १२; ६. ७३, १; ८८, २; १०३, १; ७. ९, १; ३४, १; ५३, १; ८६, ६; ११५, ३; ८. ५, ५; १३, १५; ९. ४, १०; १०, २; १२, ५; १०. ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २२; २३; २४; २५; २६; २७; २८; ११. ३, १; १०, ५; १२, १०; १२; १३; १२. ४, ३८; १४. १, ५२; ५४; ५५; १५. १०, ६; १४, १७; १६. ३, ५; १८. १, ४७; ३, ४१; ४, १५; १९. ४, ४; ९, ६; ११; १३, ९; १७, १०; २०, १; २४, ४; ८; २६, ४; ३१, ५; ४०, १; ५८, २; २०. १६, ३; ४; ५; ६; ७; ८; ९; ११; १२; १७, ११; ८८, १; ४; ५; ८९, ११; ९०, १; २; ३[२]; ९१, ३; ४; ५; ८; ९४, ११; ९६, ९.
वृहस्पतिःऽइव ९. ३, २.
वृहस्पतिना ७. १०९, १; ११. ४, १; १४. २, ५३; ५४; ५५; ५६; ५७; ५८; २०. १६, १०; १३७, ९.
वृहस्पतिऽप्रनुत्तानाम् ८. ८, १९.
वृहस्पतिऽप्रसूताः ६. ९६, १.
वृहस्पतिम् ३. २०, ४; ७; २१, ८; ४. १, ७; ९. ४, ८; ११. ८, १; १५. १०, ४; ५; ९; १९. १८, १०; २०. १६, १; ९१, ९; १०.
वृहस्पते १. ८, २; ५. २६, १२; ७. १७, १; ५५, १; १४. २, ४२; १९. १३, ८; २०. १६, २; १७, १२; ८७, ७; ८८, २[२]; ३; ६.
वृहस्पते ११. १२, ९; १३; १२. ४, ४४; ४६; १३. १, ३१; १४. १, ६२; १९. ४, ३; २०. १३, १.
वृहस्पतेः ९. ४, १३; १४. १, ५३; १६. ८, १०.
बोधिषे ६. ६३, ३; ८४, ४.
बोध २०. ११७, ३.
बोध १९. ४९, ५.
बोधः ८. १, १३.
बोधतम् २०. १३९, ३; १४०, ४.
बोधतु ७. ५०, १.
बोधन्तु ८. ७, १९; २०. ७४, ४.
बोधऽप्रतीबोधौ ५. ३०, १०.
बोधय १०. १, १७; १९. ६३, १; २०. ८९, २; १४२, २.
बोधि ४. ३२, ६; २०. ७२, ३; ९४, ९; ९५, २.

बोभुवती ५. ७, ८.
ब्रध्नः ७. २३, २.
ब्रध्नम् १९. ४९, ४; २०. २६, ४; ४७, १०; ६९, ९.
ब्रध्नऽलोकः ११. ५, २.
ब्रध्नस्य १०. १०, ३१; ११. ५, १; २; १३. १, १६; २०. ९२, ४.
ब्रध्नान् १९. २७, ४.
ब्रवः ७. २, १; ५, ५; १८. १, ७.
ब्रवत् १. १६, १; ६. ५, ३; ८७, ३; १४१, १.
ब्रवाथ ७. ५८, ७.
ब्रवावहै २०. ४५, ३.
ब्रवीतु १. ७, ४.
ब्रवीतु ९. १४, ५; १२. १, ५९.
ब्रवीमि १३. २, ४४; ४५.
ब्रवीमि ५. ११, ६; ८. १, १०; १२. २, २१.
ब्रवीषि ५. ११, ७.
ब्रह्म १. १०, ४; १९, ४; ३२, १; २. १२, ६; १५, ४; ३. १९, १; २०, ५; ३०, ४; ४. १, १; ३; ११, ११; ३४, १; ३५, २; ४०, ८; ५. २, ८; ६, १; ८, ६; ७. १०५, १; ८. २, १०; २५; १३, १५; १६; ९. २, १६; ६, १; १२, ९; १५, १९; १०. २, २१[४]; २३[४]; २५[२]; २९; ३३; ५, ४०; ७, १०; ११; १७; १९; २४; १०, ३३; ११. ३, १; ७, ५; ७; १०; २२; २३; २४[२]; ९, ४; १०, २; २३; ३०; ३२; १२, १७; १२. १, १; ५, ४; ६, २; १३. १, ३३; २, १३; ६, १; १४. १, ५४; ६४[४]; १५. १, ३; ३, ७; ६, ८; १०, ३; ४; ५; ७; ८; ९; १४, २३; १६. ८, १; ५;[२] ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; १८. १, ३७; ३, ३९; १९. ९, १२; १०, ७; ११, ४; १९, ८; २२, २१; २३, ३०; ४०, २; ४२, १[२]; २[२]; ४३, ८; ५३, ८; ९; ५४, १; २०. ८, १; ९, ३; २३, ३; ३४, १५; ४९, ६; ८५, ३; ९२, ६; १०७, ११; ११७, ३; ११९, १.
ब्रह्मऽआहुतौ १३. १, ४९.
ब्रह्मऽइद्धौ १३. १, ४९; ५०; ५१.
ब्रह्मऽओदनः ११. १, २०.
ब्रह्मऽओदनम् ४. ३५, ७; ११. १, १; २७.
ब्रह्मऽओदनस्य ११. १, २३.
ब्रह्मऽओदनाय ११. १, ३.
ब्रह्मऽओदने ११. १, २६.
ब्रह्मऽकिल्बिषे ५. १७, १.
ब्रह्मऽगवी ५. १९, ४; १२. ७, १; ४; १६; ८, ११; ९, ३; ६.
ब्रह्मऽगवीम् १२. ५, ५; ६, ५.
ब्रह्मऽचर्यम् ७. ११४, ७.
ब्रह्मऽचर्येण ११. ७, १७[२]; १८[२]; १९[२].
ब्रह्मऽचारिणः ११. ७, २०; २१.
ब्रह्मऽचारिणम् ११. ७, २; ३; १७.
ब्रह्मऽचारिणि ११. ७, २२.
ब्रह्मचारिऽभिः ६. १०८, २; १९. १९, ८.
ब्रह्मऽचारी ५. १७, ५; ६. १३३, ३; ११. ७, १; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १५; १६[२]; २४; २६.
ब्रह्मऽजाया ५. १७, ३; ४; ७; १२; १३; १४; १५; १६; १७.
ब्रह्मऽजायाम् ५. १७, २; १०; ११.
ब्रह्मऽजुष्टम् २. ३६, २.

ब्रह्मऽजूतः २०. ११, १; ३७, ११.

ब्रह्मऽजूताम् ६. १०८, २.

ब्रह्मऽज्य ५. १९, १२; १३; १४.

ब्रह्मऽज्यम् ५. १९, १५; १२. ७, ४; ८, ११; ९, ३; १०, ६; ११, २.

ब्रह्मऽज्यस्य ५. १९, ७; १२. ७, ५; १६; ९, ६; १०, १४; ११, ४; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.

ब्रह्मऽज्येयम् १२. ४, ११.

ब्रह्मऽज्येष्ठा १९. २२, २१; २३, ३०.

ब्रह्मणः ३. १६, १; ४. १, ३; ५. ६, ९; ६. ४, १; ५, ३; ७४, १; ८७, ३; ७. ३१, १; ८. ९, ७; १०. २, २८; २९; ३०; १०, १९; ११. ७, ५; ८, ४; ११, २५; १२. २, ६; १०, ८; १३. १, ५१; ३, ७; १४. १, ३१; १५. ६, ९; १९. ३०, ३; ४२, १[२]; ७२, १; २०. ९१, ७.

ब्रह्मणः २०. ३४, ६.

ब्रह्मणः १. २९, १; ४. ४, ६; ६. ६, १; ४५, ३; १०१, २; १४०, १; ७. ५८, ४; ८. ६, १५; १९. ८, ६; २४, १; ६३, १.

ब्रह्मणा १. ८, ४; ९, ३; १०, १; १४, ४; २३, ४; २. २, १; १०, १; २; ३; ४; ५; ६; ७; ८; १२, ७; ३२; ३; ३. ६, ८; १५, ३; १९, ३; ४. ३७, ११; ५. २, ५; २०, १०; २३, १०; २६, १२[२]; ६. ११३, १; ३; १३३, ३; ७. १, १; ८३, २; १०२, २; ८. ८, १९; ९. ३, ८; १९; १०. १, १२; १४; २, २५; ५, १५; १६; १७; १८; १९; २०; २१; ४२; ६, ३०; ३५; ८, १९; १०, ४; ६; ११. १, १८; ३, १५; ४, ४; ६, २४; १०, ३०; १२, ९; १२. १, २९; २, ३२; ३, २२; ५, १; १३. १, ९; ३३; ४८; ४९; १४. २, १२; ३५; १५. १४, २४; १७. १, १२; १४; २७; २८; १८. ४, ८; ५२; १९. ९, ५; २२, २१; २३, ३०; २७, १; ४२, १; २; ५४, ५; २०. ८६, १; ९६, ११; १२; १०७, ८.

ब्रह्मणा १०. १०, २५.

ब्रह्मणाम् ५. १८, ७; ६. १२२, ५; १०. ९, २७; ११. १, २५; २७.

ब्रह्मणि ५. २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.

ब्रह्मणे १०. ७, ३२; ३३; ३४; ३६; ८, १.

ब्रह्मणे ३. २८, २; ४. ३५, १; २; ९. ५, ७; ९; १०; ११; १२; १४. २, ४१; ४२; १९. २२, २०; २३, २९; ४३, ८.

ब्रह्मण्ऽवति ८. १३, १३.

ब्रह्मण्ऽवतीम् ६. १०८, २.

ब्रह्मऽतेजाः १०. ५, ३१.

ब्रह्मऽद्विषः २०. २२, २; ९३, १; ९६, ४.

ब्रह्मऽद्विषम् २. १२, ६.

ब्रह्मऽद्विषे ४. ३०, ५; ८. ४, २; २०. ३६, ८.

ब्रह्मऽनुत्तम् १०. १, १३.

ब्रह्मऽपूताः १३. १, ३६; ४३.

ब्रह्मऽप्रियम् २०. २५, २.

ब्रह्मऽभागम् १४. २, ४२.

ब्रह्मऽभिः १०. १०, २३; २०. १२०, २.

ब्रह्मऽभिः ६. १२, २; १०. १, ३.

ब्रह्मऽभ्यः १२. २, ३४; ४, १; १०; ३०; ३३; ३४; ४०; ४७; १४. १, १५.

ब्रह्मऽयुजा २०. ३, २; ३८, २; ४७, ८; ८६, १.

ब्रह्मऽयोगैः १०. ५, १.

ब्रह्मऽराजन्याभ्याम् १९. ३२, ८.

ब्रह्मऽलोकम् १९. ७१, १.

ब्रह्मऽवर्चसम् १९. ७१, १.

ब्रह्मऽवर्चसी ८. १३, १६; १५. १०, ८.

ब्रह्मऽवादिनः ११. ३, २६; १५. १, ८.

ब्रह्मऽवाहः २०. २३, ३.

ब्रह्मऽविदः १०. २, ३२; ७, २४; २७; ८, ४३; १९. ४३, १; २; ३; ४; ५; ६; ७; ८.

ब्रह्मऽवृद्धौ १३. १, ४९.

ब्रह्मऽशुम्भितः ४. २४, ४.

ब्रह्मऽसंशितम् १९. ९, ४.

ब्रह्मऽसंशिता १९. ९, ३.

ब्रह्मऽसंशिताः ११. १२, १०.

ब्रह्मऽसंशिते ३. १९, ८.

ब्रह्मसंशिते इति ब्रह्मऽसंशिते ८. ३, २५.

ब्रह्मा २. ७, २; ५. १७, ८; १८, ८; ८. ९, ३; ९. १, ६; ४, ११; १५, १४; १०. ७, २४; १०, २२; १२. २, ६; ३९; १४. १, २८; २९; ३०; १८. ४, १५; १९. ९, १२; २२, २१; २३, ३०; ४३, ८[२]; २०. २, ३.

ब्रह्माऽइव ६. ५०, २; २०. ६०, ३.

ब्रह्माणः २. ६, २; ९, ४; १२. १, ३८; ४, ३१; १४. १, ३; १६; २०. ३, ३; ३८, ३; ४७, ९.

ब्रह्माणः ६. ६८, ३.

ब्रह्माणम् ३. २०, ४; ४. ३०, ३; ५. ८, ५; १९, ८.

ब्रह्माणि ८. ४, ६; २०. ३, २; १२, १; ३; ३५, १; १६; ३७, ६; ३८, २; ४७, ८; ७३, १; ८४, २; ३; १००, २; १०४, ३.

ब्राह्मणः ४. ६, १; ५. १७, ९; १८; १८, ६; १९, ६; ९. १, २२; १२. ५, ४; १९. ६, ६.

ब्राह्मणम् ७. ६८, १; ६९, १; १०. ७, १७; ८, २०; ३३; ३७; ३८; ११. ७, ५; २३; १२. ४, २०.

ब्राह्मणम् ५. १८, ४; १३; १९, २; ३; ६; ११. ४, १७; १२. ५, ५; ६, ५; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.

ब्राह्मणऽवर्चसम् १०. ५, ३७; ३८; ३९; ४०; ४१; १३. ५, १; ६, १.

ब्राह्मणऽवर्चसेन १३. ८, ४; ५; ६; ९, १; २; ५; १७. १, २१.

ब्राह्मणस्य ५. १७, ६; १८, १; २; ३; १०; १५; १९, ९; १०; ११. ७, १०; १२. ३, ४४; ९, ८; १०, १२.

ब्राह्मणाः २. ६, ३; ४. १५, १३; ५. १८, ९; ९. १५, २७; १२. ४, १५; १६; २२; २६; १४. १, ३९; १९. ३४, ६; ३५, २.

ब्राह्मणाः १२. ४, ४८.

ब्राह्मणात् २०. २, ३; ६७, ६.

ब्राह्मणान् १०. ५, ४१; १८. ३, ५५; १९. ५९, २.

ब्राह्मणानाम् १२. ४, १२; १४; ७, ६.

ब्राह्मणीम् ५. १८, १२; १९, ११.

ब्राह्मणे ६. ३८, १; ९. ४, ९; १८; ५, १९.

ब्राह्मणेन १२. ३, २०.

ब्राह्मणेन ४. १९, २.

ब्राह्मणेभ्यः ६. १३, ३; ९. ४, १९; १०. १०, ३३; १२. ४, २१.

ब्राह्मणेषु ४. ३४, ८; ११. १, २८.
ब्राह्मणैः १२. ४, २५.
ब्राह्माः १०. २, २९.
ब्रुवते २०. १३८, ३.
ब्रुवन् ४. ८, २.
ब्रुवन्तु ४. २७, १; १८. ३, ४५; २०. ६८, ५.
ब्रुवे ५. २२, ११; २०. १८, ६; १९, ५; १०८, ३.
ब्रूत ३. २६, १; २; ३; ४; ५; ६; ४. ११, ५; ८. ९, १७.
ब्रूतम् ४. २८, ७.
ब्रूते १४. २, ६३.
ब्रूमः ५. २२, ८; ११. ८, १; २[२]; ३[२]; ४; ५[२]; ६[२]; ८; ९; १०; ११[२]; १४[२]; १५; १६[२]; १७; १९; २०; २१.
ब्रूयात् ११. ३, २४; १२. ४, १; १५. ११, २; १२, २.
ब्रूहि १. ७, ५; २. २७, ७; ८. २, ७; ८; ३, ८; १०. ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १८; १९; २०; २२; ३९; ११. २, २०; २०. ३५, १३.

भ

भंसंसः २. ३३, ५; ८. ६, ५; ९. १३, २१; २०. ९६, २१.
भक्तिऽवांसः ६. ७९, ३.
भक्त्वा ५. १७, ११.
भक्षः ४. २१, ५; ८. ७, १२.
भक्षत २०. ५८, १.
भक्षम् १. ३३, ३; ९. ४, ५; १४, २२; १३. २, १५; १८. ३, ५४.
भक्षयति ९. ११, ७; ८; ९; १०; ११.
भक्षयन्तः २. ३५, १.
भक्षयन्ति ७. ८६, ६; १८. ४, ३.
भक्षि ३. १६, २.
भक्षीमहि १९. ८, ५; २०. ८७, ६.
भर्ग ३. १६, ३[५].
भग ३. १६, ५[२].
भर्गः १. २६, २; २. ३६, ७; ३. १२, ४; १६, ५; २०, ३; ४. २१, ५; ५. २६, ९; ६. ४, २; ५३, १; ७४, १; ८२, २; १०३, १; १११, ४; १२९, ३; ७. ५२, २; ८. १, २; १२. १, २५; ४०; १४. १, २०; ५०; ५१; ५३; ५४; ५९; ६०[२]; २, १३; ५५; १९. १०, २; ४५, ९.
भर्गःऽइव ६. २१, २; २०. १६, २.
भर्गम् १. १४, १; ४; २. ३६, २; ३. १६, १; २[२]; ६; ४. ३०, ६; ५. ७, ४; ११. ८, २; १२. १, ५; १४. १, ३१; १८. १, २३; १९. ७, ५; २०. ८९, ३; ११८, १.
भगऽवः १९. ३४, ८.
भर्गऽवती ७. ७७, ११; ९. १५, २०.
भर्गवती इति भर्गऽवती २. ८, १; ६. १२१, ३.
भर्गवत्ऽतमः २. ९, २.
भर्गवत्ऽतरः ४. १३, ६.
भर्गवत्ऽभ्यः ५. ३१, ११.
भर्गऽवन्तः ३. १६, ४; ५; ७. ७७, ११; ९. १५, २०.
भर्गऽवान् ३. १६, ५; ४. १३, ६.
भर्गस्य २. २९, १; ३६, ४; ५; ६. ७४, २; १०२, ३; ९. ४, १२; १४. २, १५; २१; १९. ४, ३; ४९, १.
भर्गाय ७. १६, १.
भर्गासः २. ३०, २.
भगिनम् ६. १२९, १; २; ३; ७. १३, ३.

भगेन २. ३०, ५; ३६, १; ३. २२, ६; ६. १२९, १; २; १४. १, ३४; १९. ४५, ९.

भङ्गः ११. ८, १५.

भङ्गुरऽवतः ७. ७४, १; ८. ३, २२; २३; ४, ७.

भङ्ग्धि ३. ६, ३; ८. ३, ६; १०. ३, १३.

भज ३. ४, २; ४; ४. २२, २^{२}; १४. १, २५.

भजत ६. ५५, २.

भजध्वम् १२. ३, ४.

भजन्त १८. १, ४५.

भजन्तु १९. ८, २.

भजस्व ४. ३१, २.

भजात् १९. ५०, ७.

भजाम १६. ७, ६.

भजामः १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; १६. ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१.

भजामहे ६. ६६, ३; ७. ९५, २.

भजामि ११. १, ५.

भजासि १९. २४, ६.

भज्यन्ताम् ८. ८, ३; ४.

भञ्जती १०. १, १५.

भञ्जन् ११. ११, ५.

भत्स्यामि ३. ९, ५.

भद्रऽअहम् ६. १२८, १; २^{४}; ३; ४.

भद्रः १४. १, ३८; १९. ५७, ३.

भद्रऽकृत् २०. २९, १.

भद्रतः १८. ४, ५०.

भद्रऽपापस्य १२. १, ४८.

भद्रऽपापाः १२. १, ४७.

भद्रम् ४. १८, ६; २१, १; ६; ५. ३१, ११; ७. १९, २; ८३, २; ८. ४, ९; ९. ४, १; १७; १४. १, ७; १६. २, ४; १८. २, १३; ५२; ३, १४; २४; १९. ७, २; ४१, १; ४४, ३; २०. २०, ६; ५७, ९; १०७, १५; १२६, २३.

भद्रया ३. ३०, ३; ४. १२, २; ९. ४, ११; १२. १, ५२; ६३; १३. ७, १५; १८. २, ५२; २०. ७६, ८.

भद्रऽवाचः ४. २१, ६.

भद्रऽश्रुतौ १६. २, ४.

भद्रस्य ६. २६, १.

भद्रा १. १८, १; ३. ११, ७; ७. २१, ५; ८७, १; १०. १०, १५; १२. २, २२; १८. १, २०; १९. ४९, २; ८; २०. १३, ३; २५, ३.

भद्राः ३. १३, ५; १६, ७; ९. २, २५; १०. १०, १७; २०. ५८, २.

भद्राणि ३. २३, ४.

भद्रात् ५. ५, ५^{२}; ७. ९, १.

भद्राम् ६. १०८, ३.

भद्राय १३. ७, १४; २०. १०७, १५.

भद्रे १९. ४७, २.

भद्रे २. १०, ७; ६. ५५, ३; ७. ९७, १; १८. १, ५८; २०. १२५, ७.

भद्रे १०. १०, ७; १९. ४७, ७.

भद्रे इति ४. ९, १०.

भद्रेण ७. ६२, ७.

भनक्ति १०. ३, १३.

भनक्तु ११. १२, १६.

भन्दना २०. ६४, ५.

भन्दिष्ठः ४. ३३, ३.

भयताम् २०. ८९, ६.

भयन्ते २०. ३४, १४.
भयम् ४. १९, २; ५. २१, १; ८. १, १०; ८, २; १८; १९. ३, ४; २०. २०, ५; ५७, ८.
भयात् १०. ३, ४; ७.
भयामहे १९. १५, १.
भर ३. १०, ७; १२, ८; ४. २२, ६; ३२, ३; ५. ७, १; २९, ५; ६. ६३, ४; ७. ७७, ९; ११. १, १५; १८. ३, ६७; ४, ८८; २०. १५, ३; २१, ३; ३५, १२; ३६, ३; ४३, १; २; ३; ५६, ४; ६; ६८, ७; ७०, १७; ७९, १; ८०, १; ८५, ४; ८९, १; ३; ९७, १; १०८, १; ११८, २.
भरण्यः १९. ७, ५.
भरतम् १४. १, ३१.
भरतस्य २०. ६७, ४.
भरताम् ५. ७, ६.
भरति ८. ३, १५; १३. २, २६.
भरति ९. १५, २३.
भरत्ऽवाज १८. ३, १६.
भरत्ऽवाजः २. १२, २; १९. ४८, ६.
भरत्ऽवाजम् ४. २९, ५.
भरध्वम् २०. ७३, ३.
भरन् १८. ३, ३८.
भरन्त २०. १३८, २.
भरन्तः १९. ५५, १; २०. १४, १; ६२, १.
भरन्तम् १०. ८, १४.
भरन्ताम् ८. ३, १६.
भरन्ति १८. २, २८.
भरन्ति २. ३, ४; १०. ८, १५; २०. १२३, २.
भरन्ती १०. १, २५.
भरन्तु ८. १, १६; १५. ३, २.
भरम् २०. ९४, ५.
भरमाणाः ७. १०२, ४.
भरसा २. १६, ५.
भरस्व ५. २०, ४; ११; १८. ३, ९; ४, ५२.
भरामसि ६. ११, १; ८. १, ३; ९. ३, २४.
भरामहे २०. २१, १.
भरामि २०. ३५, २; ३.
भरामि ३. १२, ९; ८. २, १; २३; ७, २६; ९. ३, २३; १८. ४, ५१.
भराय ११. १, १३.
भरूजि २. २४, ८.
भरे २०. ११, ११; ४४, ३.
भरे ३. २४, १; ६. १०२, ३; ७. ५२, ३; १९. ४२, ३; २०. १५, १.
भरेऽभरे ७. ५२, ४; २०. ९१, ९.
भरेम ३. १५, ८.
भरेषु ४. २९, १; २; २०. १९, ५.
भर्गः ९. १, ४; १९. ३७, १.
भर्गस्वतीम् ६. ६९, २.
भर्तवे ३. ५, ३; १८. ४, ३१.
भर्तवै १९. ३०, २.
भर्ता ११. ९, १५; १८. २, ३०.
भर्त्री ५. ५, २.
भल ७. ५८, ७; २०. १२६, २३.
भर्व ३. २३, ५; ११. २, २८; १९. २४, ५.
भव २. ६, ३[२]; ३. ४, १; १६, ५; १७, ८; २०, २; २३, ४; २८, ३; ४; ३१, ९; ४. ३१, ५; ३२, ७; ५. २८, १०; ३०, १; ६. ८४, २; ८६, १; २; ३; ९२, १; ९८, १; १२३, ५; १३३, २; १४२, १; ७. ७१, १; ८. २, २६; ९. ३, ६; २४; १०. १, २९; ११. २, ३; ५; २५; १२, ६; १२. १, ३२; १०, १२; १३[२]; १४.

२, २७[२]; ३२; ४०; **१७.** १, १०; **१८.** २, १९; ३, ५०; **१९.** ४, ३; २५, १; ६४, ४; **२०.** १९, ६; ५६, ५; ८३, २.
भवः **८.** ८, १७; **११.** २, ८[२]; २७[३]; **१५.** ५, २[२]; ५; ७; ९; ११; १३; १५.
भवत् **१०.** ८, २२; **१४.** २, २४.
भवत **५.** १२, ५; **७.** ६२, ७; **१२.** २, २०; ३, २९.
भवतः **१८.** १, २९.
भव॑तम् **४.** २६, २; ३; ४; ५; ६.
भवतम् **१८.** ३, ३९.
भव॑ताम् **७.** २१, १.
भवताम् **१९.** १०, १.
भव॑ति **२.** १, १; **५.** १८, ८; **९.** १, ११; १२; १३; २, २५; ५, ३१; ३२; ३३; ३४; ३५; ३६.
भवति **३.** २२, ४; **५.** १७, ५; १८, १३; **६.** ११, २; **८.** ५, १२; १०, ३; ५; ७; ९; ११; १३; १३, ४; ८; १२; १६; १४, ४; ८; १२; १६; **९.** १, २२; २३[२]; २४; ५, २४; २८; ९, १०; १०, ३; ५; ७; १०; **१०.** ८, ११; **११.** ३, ११; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ५, २; ५; **१२.** २, ३७; ४, ४०; ९, ७; **१३.** ३, १३[२]; **१४.** १, २६; २७; **१५.** २, ४; १२; १८; २४; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ८, ३; ९, ३; १०, ८; १०; ११, ७; ९; ११; १२, ६; १०; १३, १४; **१९.** २६, १; २; **२०.** ९६, ४.
भव॑तु **९.** १३, १०.
भवतु **१.** २०, १; **२.** १३, ४; **३.** १४, ५; १५, ५; ३०, २; **४.** ३, ६; १२, ३; १५, १६; **६.** ९१, २; **७.** ९६, १; **९.** १३, १०; **१०.** ९, २; **१४.** १, ४०; **१८.** ३, ६०; **१९.** ९, ६; १०, ३; ७; ९; १०; ११, ३; **२०.** १२५, ६; १४३, ८.
भव॑त्ऽवसुः **१३.** ९, ३.
भव॑थ **१.** ४, ४.
भवथ **१.** ४, ४; **१९.** २, ४.
भव॑थः **२०.** १४१, २.
भव॑न् **३.** २९, २; **९.** १०, ६; **१८.** ४, ५१; **२०.** २९, ५; ७७, ७.
भव॑न्तः **६.** ६२, ३; **१२.** २, ११; २८.
भव॑न्ति **१.** ३३, ३; **५.** २, ३; **१२.** २, २५; **२०.** १०७, ६.
भवन्ति **५.** २७, १; **९.** ५, २५; २६[२]; १५, १७; **११.** ७, १; ८; **१३.** ४, १३; ५, ८; **१५.** ३, ११.
भव॑न्ती **९.** १५, ७.
भव॑न्तीः **३.** १४, ६.
भवन्तु **१.** ६, १; ९, २; ४; ३३, १; २; ३; ४; **२.** ३, ६; १०, ३; **३.** ४, ३; १९, ३; **४.** १५, १६; २७, ३; ३५, ७; **५.** ३, १०; ११, ६; २२, १; **६.** २३, ३; **७.** ७२, १; **९.** २, ७; **१२.** १, ३१; २, २१; ३, ३१; **१४.** १, ४०; २, ९; **१८.** ३, ६१; ४, ३३; ४८; **१९.** ९, ९; १३; १०, ५; ७; ८[२]; ९; १०; ११, १[२]; २; १३, ११; १४, १; १५, ६; ४०, ३; ४५, ४; **२०.** ७६, ६; ९१, ११.
भवम् **१५.** ५, १.
भवसि **७.** ८६, २; **१०.** ८, २७; **१२.** ३, २१; **१४.** १, २४.
भव॑स्य **८.** ८, ११.

भवा॑ति १८. १, २; १२; २६; ३४.
भवाति २. ३६, ३; ६. १२०, २; १८. २, ५; २०. २०, ६; ५७, ९; १२४, ३.
भवाथः १२. ३, २; ९; १४. २, ३७.
भवा॑म १९. ४९, ६.
भवामि ५. ११, २; ६. ११७, १; २.
भवाय॑ ६. ९३, २; ११. २, ९; १६.
भवारुद्रौ ११. २, १४.
भवाव १४. २, ७१.
भवा॑शर्वौ ४. २८, १; ८. २, ७; ११. २, १.
भवाशर्वौ ४. २८, ७; १०. १, २३; ११. ८, ९; १२. ४, १७.
भवा॑सि ३. २३, ३.
भवित्र॑म् १९. १०, ९.
भविष्यत् ४. ११, २; १०. ७, ९; ११. ६, २०; ९, १७; १३. ३, ७; १५. २, ६.
भविष्यति॑ ८. १०, १; २०. १२६, ७.
भविष्यति ११. ६, ५.
भविष्यन् १२. ३, १९; ५३.
भविष्यसि ११. ४, २; ३; १४; १५; ६, २६.
भवी॑यसा २०. २५, १.
भवे॑म १९. ६७, ६.
भवेम ६. ११९, २; १२. ३, १०; ५५; ५६; ५७; ५८; ५९; ६०.
भव्य॑ः १३. १, ५५.
भव्य॑म् २. १५, ६; ६. १२, २; ११५, २; ९. १५, २४²; १०. ७, २२; ८, १; १२; ११. ६, १५; २०; १३. ६, २; १७. १, १९; १९. ९, २; ५३, ५; ५४, ३.
भव्य॑स्य ६. ३६, ३; १२. १, १.
भव्या॑त् १९. ३५, ४.
भव्ये॑ १७. १, १९.
भव्ये॑न १७. १, २९.
भसत् ९. ४, १३; १२, ८; १०. ९, २१; २०. १२६, ७.
भसद॑म् ४. १४, ८.
भसद्यमि २. ३३, ५; २०. ९६, २१.
भस्म॑ ११. ३, ८.
भाः ७. १५, २.
भाःऽऋ॑जीकः १८. १, ३०.
भागः ६. ८४, २; १४०, २; ७. ७७, ४; ९. ४, ५; १०. ५, ७; ८; ९; १०; ११; १२; १३; १४; १५; ११. १, ५; १५; १२. २, ९; ३, ४५; १४. २, ३३; १८. २, ८; ४, ५४; २०. ३६, ४.
भागऽधेय॑म् ६. १११, १; ११६, २; ७. ८४, १; ११. १, २९; १२. २, १; ५३²; १८. २, ३१; १९. ५८, ६.
भागम् २. ३४, १; ४. ३९, ९; ५. १९, १३; १४; ६. ६४, १; १२२, १; ७. ७५, १; ८६, २; ८. ३, १६; ९. ५, २; १५, १५; ११. १, १६; २९; १२. ४, २१; १४. १, २४; ३३; १८. १, २६; ४३; ४, ४७; १९. ५४, ४; २०. ५५, ३; ५८, १.
भागस्य॑ २०. ६७, ५.
भागे ८. १, १.
भाजयत १. ५, २.
भाति ८. ३, २४; ११. ९, १४; १३. १, ११; ३, १६; १८. ३, ६५; ४, १४.
भानव॑ः ४. ३३, ५; १३. २, ४६.
भानुः १९. ७, २.
भानुना॑ २०. १७, ९; १४२, ३.
भानुम् १८. ३, २९.
भार्म॑ः ४. ३२, ४.
भार्मा॑य १४. २, ३५; १८. ४, ८२.

भामिनः १८. १, ६.
भारः ९. ३, २४.
भारती ५. १२, ८; २७, ९.
भारम् ९. १५, २३.
भावयति १२. ९, ५.
भावयुः २०. १२६, १५.
भाव्यमि १३. १, ५४; १९. ६, ४.
भासति १३. ४, ७.
भासदम् २. ३३, ५; २०. ९६, २१.
भासि १३. २, १०; १९; २८; १७. १, १६; २०. ४७, १६.
भाहि २. ६, १; १९. ३३, ५.
भिक्षाम् ११. ७, ९.
भित्त्वा २०. १६, ७.
भिदेयम् ९. २, २.
भिनत् २०. १६, ११; ९२, ११.
भिनत्तु ६. १३८, २.
भिनद्मि २. ३२, ६; ४. ३७, ७; ५. २३, १३.
भिनद्मि १. ३, ७; ११, ५; ६. १३८, ४; ५.
भिन्दत् ५. २८, १४.
भिन्दन् ८. ४, २१.
भिन्दन्तः १८. ३, २१.
भिन्दन्ति ६. १३८, ५.
भिन्दन्ति ५. १८, ९.
भिन्द्धि ७. १९, १; १९. २८, ४; ५.
भिन्द्धि ३. ६, ६; १९. २८, ३.
भिन्द्यात् ९. ५, २३.
भिन्धि २०. ४३, १.
भिन्धि ४. १९, ५; ८. ३, ४; ११. १, ९.
भिन्नाम्ऽइव ५. १९, ८.
भियः ४. ३१, ७.
भियम् ६. ६७, ३.
भियसम् ५. २, २; २०. १०७, ५.
भियसा ५. १३, २.
भियसाने इति ४. २, ३.
भिया ११. ११, १२; २०. ३५, १४.
भिषक् ५. २९, १; १०. ४, १५.
भिषक्ऽतराः १९. २, ३.
भिषक्ऽभ्यः १९. २, ३; ५६, २.
भिषक्ऽभ्याम् १०. ६, १२.
भिषजः २. ९, ३; २९, ७; ८. ७, २६.
भिषजा २. ९, ५; ७. ५५, १.
भिषजाम् ६. २४, २.
भिषज्यथः २०. १४०, १.
भीतः १३. २, ३७.
भीता ५. २०, ५.
भीमः ७. २७, २; ८९, ३; ८. १, १०; ९. १३, ६; १९. १३, २; २०. ३७, १.
भीमऽतमा १२. ४, ४५.
भीमम् ११. २, १८; १८. १, ४०.
भीमा ३. २५, १; ५. १७, ६; १०. १, २९; १२. ४, ४८; ७, १.
भीमाः ४. ३७, ८; ९; ५. २२, १०.
भीमाम् १२. ४, ४१.
भीमाय २०. १५, ३.
भुजः २०. ५५, २.
भुजम् ८. २, ८.
भुजिष्यमि १२. १, ६०.
भुज्मा २०. ५१, ४.
भुनजामहै ६. २४, ३.
भुरणौ २०. ७६, १.
भुरण्यथः २०. १४०, १.
भुरण्यन्तम् १३. २, २१; २०. ४७, १८.
भुरण्युम् १८. ३, ६६.
भुवः ३. १७, ८; ६. १०६, ३; १३. ९, १;

१८. २, ३२; २०. ३६, ९; ६०, ३; ९३, ८.

भुवः १०. ५, ४५[२]; १८. ३, ६०.

भुवत् १. २२, २; ३. २०, ६; १०. ८, ११; २०. ५९, ४.

भुवत् ३. ३, १; ५. ३०, १४; ७. १, २[२]; १९. २६, ४[२]; २०. ३५, १४; ४७, १; ६९, १; ७७, ८; १२४, १; १२६, ६; १३७, १२.

भुवनऽच्यवानाम् १९. १३, १०.

भुवनम् ३. २१, ५; ४. ११, १; १०. ७, ३५; ८, ७; १३; ११. ६, २२; १३. ३, १५; १८. १, ५३.

भुवनस्य २. २, १; २; ३४, २; ५. ३, ९; ७. ८६, ६; ९. १४, २२; १५, १३; १४; १७; २१; १०. ७, ३८; ८, १५; १२. १, ५७; १३. १, १४; ३७; ४२; २, २; ३, ७; १८. २, ५४; १९. २०, २.

भुवना २. १, ३; ४. ११, २; ६. ३४, ४; ७. ८६, १; ९. १, ५; १४, २; १३. २, ११; ३, १८; १४. १, २३; १७. १, १६; २०. ६३, १; ७७, ५; १२४, ४.

भुवनानि २. १, ३; ५; ३. २०, ८; ४. २५, ३; २६, ५; ३०, ७; ८; ५. ११, ४; १२, ९; ७. २७, ३; ९२, १; ११५, २; ९. १४, ११; १४; १०. ८, १८; ११. २, ११; ७, ९; १३. २, ९; ३८; ३, १; ३; १४; १९. ५३, १; २; ३; ४[२]; २०. ११८, ४.

भुवने १२. १, ३१; १८. १, १७; १९. ७, १.

भुवनेभ्यः २०. १३७, १०.

भुवनेषु ५. २, १; ९. १५, ११; १०. २, ७; २०. १०७, ४.

भुवनेऽस्थाः २. १, ४; ४. १, २.

भुवम् २०. १२६, ५.

भूः ६. ९८, २; १८. १, २५; २०. ३७, १०.

भूःऽजयः १८. १, ६१.

भूत् ५. ११, ७; ७. ३६, ३; ११३, १; ८. १, ७; ४, ७; २०. ७६, ३.

भूत १८. ३, १९.

भूतः ४. ८, १; ११. ६, १; २०[२]; १३. १, ५५; ३, ७.

भूतऽकृतः ३. २८, १; ४. ३५, २; ६. १०८, ४; १३३, ५; ११. १, १; ३; २४; १२. १, ३९; १९. १६, २; २७, १५.

भूतऽकृताम् ६. १३३, ४.

भूतऽपतिः २. १४, ४.

भूतऽपतिम् ११. ८, २१.

भूतपती इति भूतऽपती ११. २, १.

भूतऽभव्यम् ११. ७, २०.

भूतम् २. १५, ६; ४. ११, २; ६. १२, २; ११५, २; ८. ९, १८; ९. १५, २४[२]; १०. ६, १८; २१; ७, ९; २२; ३१; ८, १; १२; ११. ६, १५; ८, २१; ९, २; १७; १३. १, ५४; २, ४१; ६, २; १५. २, ६; १७. १, १९[२]; १९. ६, ४; ९, २; ५३, ५; ५४, ३; २०. १४१, १.

भूतस्य १. ३१, १; ३२, २; ३. १०, ९; १०; ४. २, ७; ५. २५, ७; ६. ३६, ३; ३९, ३; ५८, ३; ८६, १; ९५, ३; १०. १, २२; १२. १, १; १३. १, ४५; १४. २, ४६; १९. ३७, ४.

भूता ६. ८०, १; ८. ९, १६; २१; १३. २, १२.

भूतात् ६. १३३, ३; १९. ३५, ४.

भूतानाम् ४. ८, १; ५. २५, २; ६. १७, १; ११. ८, २१; १९. २२, २१; २३, ३०.

भूतानि १. २९, ३; ४. १३, ४; २०, २; ६. १९, १; १०. ५, ६; ११. ८, २१; १५. ३, १०; ११; १८. ४, ७; १९. ६, ३; ५३, ६.
भूतिः ११. ९, २२; १०, २१.
भूतिऽभिः १०. ६, २८.
भूतिम् १०. ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; ६, ९; १२. ४, २८; १९. ५३, ६.
भूतु ८. ४, ६; २०. ६३, २; ८५, ३; १२४, ५.
भूते ६. ८४, २.
भूते १७. १, १९.
भूतेन ६. ७८, १; १७. १, २९.
भूतेषु ४. ८, १; १९. ४८, ५.
भूत्या १०. ६, २४.
भूत्याः ९. १०, ३; ५; ७; १०.
भूत्याम् १२. १, ६३; ४, ४४; ४६.
भूत्वा १. ७, ६; ३. ३, ३; १८, ५; २८, २; ३०, ३; ४. ३४, ४[२]; ३७, ११; ५. ५, ९; १९, ७; ६. ४२, १; ८. ४, १८; ६, ७; ९. २, ९; १०. १, २४; ८, २१; ९, ३; १०, १६; ११. ७, ७[२]; १५; १२. ९, ३; १०, ९; १३. ३, १३[२]; १४. १, २५; ४२; १५. ७, १; २; ४; १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३; १८. ४, १०; १९. ३२, ५; ५३, ९; २०. ९६, १५[२].
भूम १३. २, ३; २०. ३५, १४.
भूम ७. २१, ३; २०. ३७, ७; ११६, १.
भूमा ५. २८, ३[३].
भूमानम् ३. २४, ७; १९. ३१, ४; ८.
भूमिः १. ३२, ३; ३. २९, ८; ४. १६, ३; ५. १८, १२; १९, ११; २८, २; ५; ६. १८, २; २१, १; ८४, १; १२०, २; १०. २, २४; २५; ७, ३; १२; ३२; ८, २; ११. ३, २०; १०, ७; १२. १, ३; ४; ६; ८; ९; १०; १२; १३; २२; २६[२]; ४०; ४१; ५२; ५९; १३. १, ४६; ५३; ७, ७; १४. १, १; ६; १५. ४, १५; ६, २; १७, १; १९. ६, ८; ९, ८[२].
भूमिऽगृहः ५. ३०, १४.
भूमिऽदृंहः १९. ३३, २.
भूमिऽदृंहम् ५. २८, १४.
भूमिम् ३. १७, ५; ४. ५, २; १५, २; ३; ६; १६, ४; २०, १; ३; ९; ४०, ५; ५. ११, ६; ८. ७, १६; १०. २, १८; ९, १०; ११. २, २५; ७, ९; ८, १०; १२. १, ७; ११; १७; २९; १३. १, ५२; ५४; २, ४०; ४१; १५. ४, १४; १८. ३, ४९; १९. ६, १; ९; ३३, ३; २०. २७, ५.
भूमीः ११. ९, १४; २०. ८१, १; ९२, २०.
भूमे १२. १, ३३; ६३.
भूमे १२. १, १४; १८; २५; २९; ३१; ३२; ३४[२]; ३५; ३६; ५०; १८. २, ५०; ५१; ३, ५०; ४, ६६.
भूमेः १३. ७, ७; १५. ६, ३; १८. ३, ९.
भूमौ ११. ७, १२; १२. ३, १२; १८. १, ३९; १९. ८, १.
भूम्ने ६. १४१, १.
भूम्याः १. ११, २; २. ३०, १; ४. १९, ६; ५. २०, ६; २८, ९; ६. ८९, ३; ९. १४, ४; १०. १, १३; १२. ३, २६; १४. १, ४८; १९. १६, २; २७, १५; २८, ४; २०. १६, ४.

भूम्याम् २. ९, ४; ६. ८, २; १२१, २; ९. १, १०; २०; १०. ९, १२; ११. ६, ४; ९, १६; १२, २३; १२. १, १३; १९; २२[२]; २८; ४१; ५२; ५४; ५६; १९. ३४, ६.
भूम्यै १२. १, ४२.
भूयः ३. १९, ५; ९. ७, २; १३. २, २५; २७[२].
भूयःऽभूयः ४. २१, २; १०. ६, ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
भूयसीः १९. ६७, ८.
भूयसीम् १८. ४, २७.
भूयांसः ७. ६२, ७.
भूयाः ५. २२, २; ६. १२५, १; ७. ७७, ११; ९. १५, २०; २०. १७, ९.
भूयाः३ ९. ७, १.
भूयात् ४. २२, ४.
भूयान् १३. ८, १[२]; २.
भूयासम् १. ३४, ३.
भूयासम् ३. ५, २; ६. १५, २; ३; ७. ५२, ८; ८६, ४; १३. १, ३८; १६. ३, १; ४, १; ९, ४; १७. १, १; २; ३; ४; ५; १८. २, ४५; १९. ५५, ५.
भूयास्थ १८. ४, ८६.
भूयास्म ७. ६३, १; १८. ४, ८७.
भूयेम १९. ६७, ७.
भूरयः १८. ४, ५५.
भूरि ४. २२, ४; ३०, २; ३२, ७; ५. २, ३; ५; ६; ११, ७; २२, ६; ६. १, ३; ७. १९, ३; १८. २, ६०; २०. १५, ५; ५६, २[२]; ८९, ८; १०७, ६; ८; ९.
भूरिऽओजाः ५. २, २; ७; २०. १०७, ५; १०.
भूरिऽदात्रः २०. ११, १.
भूरिऽधनाः ७. ६२, ४.
भूरिऽधायसम् १. २, १.
भूरिऽधायसे ६. ४१, २.
भूरिऽधारा १२. १, ९.
भूरिऽपाणिः ५. २७, १.
भूरिऽभारः ९. १४, ११.
भूरिऽभिः १८. १, २२.
भूरिम् २०. ७७, ८.
भूरिऽमूलः ६. ४३, २.
भूरिऽरेतसा ८. ९, १२.
भूरिऽरेताः १९. ५३, १.
भूरिऽवर्पसम् १. २, १.
भूरिऽस्थात्राम् ४. ३०, २.
भूरीणि २०. ३७, ४.
भूरेः २०. ३५, १५; ४३, ३.
भूर्णयः ५. ६, ३.
भूवन् २०. ६७, २.
भूष १४. २, २५.
भूषत २०. ९७, १.
भूषति १८. १, २४; २०. ९७, २.
भूषतु २०. १०४, ३.
भूषन् २०. ११, २.
भूषन्ऽइव २०. ८९, १.
भृगवः १८. १, ५८; २०. १०, २; ५९, २.
भृगवे २०. ९, ३; ४९, ६.
भृगुः २. ५, ३.
भृगुऽभिः ४. १४, ५.
भृगुम् ५. १९, १.
भृङ्गाः ९. २, २२.
भृत्याम् १८. १, ६.
भृत्यै २०. ७६, ४.
भृमलः १२. १, ४६.

भेजानः ३. १३, ६.

भेजानासः २०. ९३, ४.

भेजिरे १२. १, २३.

भेजिरे ५. ४, ८; ११. १०, ३१.

भेत् २०. १६, ६.

भेदः १२. ४, ५०.

भेदम् १२. ४, ४९.

भेषज ८. ६, १६.

भेषजम् १. ४, ४; ५, ४; ६, ३; २. ३, १; ३; ४^{2}; ५; ३. ७, १; ६; ४. १३, ३; ५. ३०, ५; ६. २१, १; २४, ३; ५७, १^{2}; २; ३^{2}; ८३, १; ९१, ३; १०६, ३; १११, २; ३; १२७, २; ७. ३९, १; ४६, १; ८०, ४; ८. २, ५; २८; ६, ३; ७, ५; २२; २६; १०. ४, १०; १४; ११. ६, ९; ८, २३^{2}; १९. ३५, १; ४४, १; २०. १४१, ५.

भेषजस्य ५. २९, १; १९. ३८, १.

भेषजा १. ६, २; ११. ८, १४.

भेषजानाम् ४. १७, १; ६. २१, २.

भेषजानि २. ३, २; ९, ५; ६. ४४, २; ७. ४३, २.

भेषजी ७. ५८, २.

भेषजीः ३. ७, ५^{2}; ६. ९१, ३^{2}; ८. ७, ८; १९. २, ५.

भेषजीम् ६. १०९, ३^{2}; ८. ७, २३.

भेषजेभ्यः ६. १३, ३.

भेषजौ ८. ६, २०; ७, २०.

भैषीः १०. ९, ७.

भोगम् २०. ११, ९.

भोगाय १२. ४, ७.

भोगाय १९. ४४, १०.

भोगे १२. १, ६०.

भोगेभिः ११. ११, ५.

भोग्यः १०. ८, २१; २२.

भोजनम् १०. ८, २१; २०. २५, ४.

भोजना २०. ९४, ७.

भोजनानि ४. २२, ६; ७; ७. ७७, ९; २०. ३७, ६; १२५, २.

भोजम् २०. ८९, ३.

भोजय १९. ५०, ६.

भौवनाः ३. २१, ५.

भ्रजः ७. ९५, २.

भ्रशत् ६. ८७, १.

भ्राजः २. ११, ५; १७. १, २०^{2}.

भ्राजत् ११. ७, २४.

भ्राजता १७. १, २०^{2}.

भ्राजन्तः १३. २, १; १८; १९. २७, ६; २०. ४७, १५.

भ्राजमानः ५. १, १; १३. १, २४; २, १०.

भ्राजमानम् १३. २, ४; ३६; ३, १६.

भ्राज्यासम् १७. १, २०.

भ्रातरः २. १३, ५; १०. ३, ८.

भ्रातरम् ३. ३०, ३; ११. ११, ८.

भ्राता ३. ३०, ३; ४. ४, ५; ५. ३०, ५; ६. १२०, २; ८. ६, ७; ९. १४, १^{2}; १८. १, १२; १३; १४; १९; २०. ९६, १५.

भ्रातुः १. १४, २; ६. ११६, ३.

भ्रातृऽभिः ६. ४, १.

भ्रातृव्यः ८. १२, २.

भ्रातृव्यऽक्षयणम् २. १८, १.

भ्रातृव्यऽघ्नी १०. ९, १.

भ्रातृव्यऽचातनम् २. १८, १.

भ्रातृव्यम् ८. १५, ४; १५. १, ८.

भ्रातृव्यस्य ९. ५, ३१; ३२^{2}; ३३^{2}; ३४^{2}; ३५^{2}; ३६^{2}; १०. ६, १.

भ्रातृव्याः १०. ३, ९.

भ्रातृव्येण ५. २२, १२.

भ्रात्रा ५. २२, १२.

भ्रूणऽघ्नि ६. ११२, ३; ११३, २.

म

मंसंसे ७. २१, २; ६.

मंस्त ८. १, १२.

मंस्थाः ९. ५, ४.

मंहते २०. ५१, ३.

मंहमानम् २०. ६६, १.

मंहिष्ठः २०. ५५, १; १२४, २.

मंहिष्ठम् २०. ३५, ३; ४४, १; ८५, २.

मंहिष्ठाय २०. १५, १.

मर्कान् ८. ६, १२.

मक्षाः ९. १, १७.

मक्षिका ११. ११, १०.

मक्षिकाः ११. २, २; १२, ८.

मक्षु २०. ९, २; ३५, १६; ४९, ५; ५२, ३; ५७, १६.

मखः १८. १, २३; २०. ४०, २; ७०, ४.

मखस्य २०. ११, २.

मखस्यते २०. १३७, ५.

मगधेभ्यः ५. २२, १४.

मगुन्द्याः २. १४, २.

मघऽदेयाय २०. ८९, २.

मघम् २०. २७, ४.

मघवत्ऽभ्यः २०. ८३, १.

मघवत्ऽसु २०. ५१, ४.

मघऽवन् १९. १५, १.

मघऽवन् २. ३६, ४; ३. १, ३; १६, ४; १९, ६; ७. ३२, १; ५२, ४; ८. ४, १९; १३. ७, १६; २०. १५, ५; १७, ५; ३७, ८; ९; ५०, २; ५२, ३; ५५, २; ५७, १६; ६७, ६; ८१, २; ८२, २; ८३, २; ८५, ४; ८९, ३; ९२, २१; ९४, ९[२]; ११७, ३; १२१, २; १२५, १; ५.

मघऽवा २. ५, ७; १४. २, ४७; २०. १४, ४; १७, ३; ५; ६; ८; ५१, १; ५३, ३; ५७, १३; ६२, ४; ७३, ४; ८७, ५; ८९, ६; ८; ९६, ४; ११३, १.

मघऽवान् ६. ५८, १; ७. ९१, १; २०. ७७, १.

मघऽवानम् ३. १९, ३; २०. ११, ११; १७, १; ५५, १.

मघाः १९. ७, २.

मघानि २०. ३७, १०.

मघासु १४. १, १३.

मघैः १८. १, ३८.

मघोनः १८. १, ३८.

मङ्गलिकेभ्यः १९. २३, २८.

मज्जऽभ्यः २. ३३, ६; २०. ९६, २२.

मज्जऽसु १. ११, ४.

मज्जा ४. १२, ३; ४; ९. १२, १८; १०. ९, १८.

मज्जानम् ११. १०, ११; १२; १२. ११, ९; २०. १६, ९.

मज्ज्ञः ९. ५, २३; १३, १८.

मज्ज्ञा ४. १२, ३; ४.

मज्मना २०. ७६, ६.

मज्मनि १३. १, १४; ३७.

मट्मटाः ८. ६, १५.

मणिः १. २९, ४; २. ४, २; ६; ४. १०, ४; ५; ८. ५, १; २; ४; १६; ७, १४; १०. ३, १; २; ३; ६; १०; १७; १८; १९; २०; २१; २२; २३; २४; २५; ६, २; ४; ५; १९; २२; २३; २४; २५[२];

२६; २७; २८; ३१^{2}; ३२; १५. २, ५; १३; १९; २५; १९. ३१, २; ६; ७^{2}; ८; १०; १४; ३३, १; ३६, १; ३; ५.

मणिना १. २९, १; २. ४, ४; ८. ५, ३; ८; १०. ६, १२; १९. ३१, १.

मणिम् २. ४, १; ३. ५, ३; ९, ६; ८. ५, ७; १०; १२; १३; १४; २२; १०. ६, ६; ७; ८; ९; १०^{2}; ११; १२; १३^{2}; १४^{2}; १५^{2}; १६^{2}; १७^{2}; २९^{2}; १२. १, ४४; १९. २८, १; ३०, ४; ३१, ४; ४५, ५.

मणीनाम् १९. ३१, ११.

मणे १०. ६, ३४^{2}.

मणे ३. ५, ८; १९. २८, ३; ४; ५; ६; ७; ८; ९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९.

मणौ ६. ३०, १; १९. ४६, ५.

मण्डूकम् ७. १२१, २.

मण्डूकाः ४. १५, १२; १३.

मण्डूकि ४. १५, १४.

मण्डूकी १८. ३, ६०.

मण्डूरऽधाणिकीः २०. १३७, १.

मत् १. ३४, ५; २. ७, १; ३०, १; ४. १९, ७; ६. ८, १; २; ३; ११८, ३; ७. ६२, १; ६७, १; १०. १, १०; १३; ११. ६, २६^{2}; १२. ३, ४६; १८. १, ९; ११; १३; २०. १२६, ६^{2}.

मतयः २०. १७, १; २३, ५.

मतस्नाभ्याम् २. ३३, ३; २०. ९६, १९.

मतस्ने इति १०. ९, १६.

मतिः ७. २३, १; ८. ४, ६; १०. २, १०.

मतिऽभिः २०. ३६, २; ९१, ९; १४०, १.

मतिम् ६. १३३, ४; ७. १५, १; २०. १५, १; ७०, २; १४२, १.

मती १८. १, २३.

मतीनाम् १३. १, ३३; ३, १९; १८. ३, ६३; ४, ५८; २०. ३५, ३.

मतेः २. ५, १.

मत्तः ६. २०, १.

मत्यम् ८. ८, ११; ११. २, १९.

मत्यै ६. ४१, १.

मत्ऽसखा २०. १२६, १.

मत्सत् २०. १२, ७; १२४, २.

मत्सरम् ४. २५, ६.

मत्सराः ७. ८२, ३.

मत्सि २०. ७१, ७.

मत्स्यम् २०. १६, ८.

मत्स्याः ११. २, २५.

मत्स्व २. ५, ४; २०. २३, ८; ६०, ३; ७१, ९.

मथंत् ७. ५२, ५.

मथव्यान् २. ३५, २.

मथायति २. ३०, १.

मथिष्यन् १९. ४०, २.

मश्नन्तु ७. ७३, २.

मश्नामि २. ३०, १; ७. ५२, ५.

मश्नीत ५. ८, ४.

मदः ६. ३०, २; २०. ५७, २; ६३, ७; ६८, २; ७६, ३; ११७, २.

मदः ८. १, ७.

मदऽच्युता २०. ५६, २.

मदति २०. १०६, ३.

मदते ४. ३४, ३.

मदनऽइव २०. २८, ४; ३९, ५.

मदन्तः ३. १५, ८; ६. २८, १; ६२, ३; १९. ५५, १; २; २०. १६, १; ८८, २.

मदन्ति ३. २८, ५; ४. ८, ५; ५. २, १; ६.

१२०, ३; ७. ७७, २; ११४, २; १८. २, ११; ४, १०; २०. १०७, ४; १०९, १.
मदन्ति ७. ११४, ३; १४. २, ३४; २०. ११, ८.
मद॑न्ती १८. १, ४३; ४, ४७.
मद॑न्तीम् १८. ४, ३०.
मदन्तु ७. १७, १; ३६, १; १२३, १.
मद॑न्तौ १८. १, ५४.
मद॑म् ४. ७, ४; २०. २२, १; २४, २; ३०, १; ३३, १; ६१, १.
मदय॑न्ति ९. १३, १९.
मदऽवति ४. ७, ४.
मदऽव॑ती ६. १६, २.
मदसि १९. ५६, ५.
मद॑स्य २०. ३१, ४.
मद॑स्व १८. ३, ८.
मदा॑ः २. ५, २; २०. १२, ५; २१,-६; २८, ४; ३९, ५; १३७, ४.
मदा॑नाम् २०. १२४, २.
मदा॑य २. ५, १; २०. ८, २; ३; ५६, १; ९४, १; १४२, २.
मदिन्ऽत॑मः ११. ९, ७.
मा॑दिन्ऽत॑रम् २०. ६४, ४.
मदि॑ष्ठः ४. २४, ३.
मदुघ॑स्य ६. १०२, ३.
मदुघा॑त् १. ३४, ४.
मदे॑ २. ५, ३; २०. ५, २; २८, १; ३१, १; ३९, २; ४७, २; ९४, ८; ९९, २; १३७, १३.
मदेत ९. १, ६.
मदे॑म ७. ५, ३; १९. १२, १; २०. ६३, ३; १२२, १; १२४, ६; १२५, १.
मदेम ६. १२२, ४; ७. ८५, १; ११४, ५; १२. २, २८; २०. ३७, ८; ९१, ९.
मदे॑ऽमदे २०. ५६, ४.
मदे॑षु ५. २, २; २०. ७५, ३; १०७, ५.
मद्य॑म् ७. ६०, १.
मद्र्यक् २०. २३, १.
मद्र्यद्रिक् २०. ३६, ११.
मद्म॑ने २०. ११०, १.
मधु॑ १. ३४, २; २. १३, १; ३. १४, ३; ५. २, ३; १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ६. १२, ३[२]; २२, २; ६९, १; ७. ७७, १; ९. १, १४[२]; १६; १७; १८[२]; २२; ९, ५; १०. ६, ५; ९, १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १२. १, ७; १६; ३, ४४; १८. २, १४; ४, ३; २०. ४, २; १६, ८; २२, ६; ६७, ५; ७; ७३, ५; ९२, ३; १०७, ६.
मधुऽअद॑ः ९. १४, २१.
मधुऽकशा ९. १, १; २; ३; ४; १०.
मधुऽकशाम् १०. ७, १९.
मधु॑ऽकूलाः ४. ३४, ६.
मधुऽकृत॑ः ९. १, १६.
मधु॑ऽजाता १. ३४, १; ७. ५८, २.
मधु॑ऽजिह्वाः ५. ६, ३.
मधु॑ऽतरः १. ३४, ४.
मधु॑ऽधारा १८. ४, ५७.
मधु॑नः २०. ६५, २; १४३, ४.
मधु॑ना १. ४, १; ३४, १; ३. १७, ९; ५. २, ३; १२, १०; २८, १४; ६. ३०, १; ६९, २; ९७, २; ११६, २; ९. १, १९; १२. ३, ४१; १८. ३, १०; १४; १८; २०. १६, ४; १०७, ६.
मधुऽपर्के १०. ३, २१.
मधुऽपूः १८. ३, ३७.

मधुऽपृचाम् ३. १३, ९.
मधुऽभागः ६. ११६, २.
मधुऽमत् १. ३४, ३[३]; ४. ३४, ९; ६; ७; ६. ६१, १; ७१, ३; ११६, १; ७. ८७, १; ८. ७, १२[५]; ९. १, २३; १२. १, ९८; २०. १४३, ८.
मधुऽमतः १. ३४, १; ९. १, २३.
मधुऽमती १६. २, १.
मधुऽमतीः ४. २३, ६; १०. ९, २७; १४. १, ३७; १६. २, २; १८. ४, ३९; २०. १४३, ८.
मधुऽमतीम् ३. ३०, २; ५. ७, ४; ८. ७, ६; १६. २, २; १८. ४, ३०; १९. ३१, १४.
मधुमतीम्ऽइव १. ३४, ४.
मधुमत्ऽतमम् १८. २, २; २०. १४०, २.
मधुमत्ऽतमस्य ७. ६०, २.
मधुमत्ऽतमाः २०. १०, १; ५९, १; १३७, ४.
मधुमत्ऽतरः १. ३४, ४.
मधुऽमन्तः ७. ७०, २; १८. ३, ६८; ४, २१; ४२.
मधुऽमन्तम् २०. ३२, ३; ११९, २.
मधुऽमान् ९. १, २२; २३; १२. ३, ६; १८. १, ४८; ४, २२; १९. ३३, २; ४६, ६; २०. ४, ३; १३९, ४; १४३, ८.
मधुला ५. १५, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ७. ५८, २.
मधुऽश्चुत् ७. ५८, २.
मधुऽश्चुतः ९. ५, १५; १८. २, २०.
मधुसंकाशे इति मधुऽसंकाशे ७. ३७, १.
मधुऽसंदृशः १. ३४, ३.
मधूः ७. ५८, २.
मधूनि ७. १०२, ३; ८. ९, १८; ९. १, २२; २०. ७६, ६.
मधूलकम् १. ३४, २.
मधोः १. ३४, १; ४; २. ५, १; २; ७. ७७, ५; ८. ७, १२; ९. १, ५; १०. ६, २५; २०. ६, ६.
मधौ ९. १, १६; १७.
मध्यतः ४. १४, ८; ७. ५३, १; ५८, ६; ८९, १; १०. २, १; १२. १, २; १३. ३, १३; १४. १, ६०; ६४; १८. ३, ७३; ४, ९; १९. १५, ३; २०. १७, ११; ८९, ११; ९४, ११.
मध्यन्दिनः ९. १०, ५.
मध्यंदिनम् ४. ११, १२; ६. १०८, ५.
मध्यंदिने ६. १२८, २.
मध्यम् ४. ११, ८; १४, ८; ५. २३, ३; ६. ८९, ३; १३७, ३; ७. ७५, २; ८. ७, १२; ९. ५, ८; २०; १०. ४, १९; १२. १, १२; १९. ६, ६; ४४, ७.
मध्यमः ९. १४, १.
मध्यमम् ५. १३, २; ७. ८८, ३; १०. ७, ८; १८. ४, ६९.
मध्यमशीःऽइव ४. ९, ४.
मध्यमा १८. २, ४८.
मध्यमाः १. १७, ३; १८. १, ४४.
मध्यमान् ६. १०३, २.
मध्यमाम् ७. ७८, २.
मध्यमे १. १७, २.
मध्यमेऽस्थाः २. ६, ४; ३. ८, २.
मध्या २०. १२३, १.
मध्यात् ४. १, ३; ५. २८, ९.
मध्ये १. ३३, २; ३. १६, ४; ४. १५, १४; १५; ५. १९, ३; ६. १०६, २; ९. १५, ८; १०. ७, ३८; ८, १५; १७; १०, २८; १३. २, ३६; १८. २, ३५; १९. १, १९; १३, ९.

मध्येन ८. ८, १३; १९. ३६, २.

मध्वः ४. ३२, ७; ७. ३, १; २०. १, १; ६, १; १३, २; ३२, २; ६४, ४; ७६, ७; ८८, ३; ९२, ४; १०९, १.

मध्वा ५. १२, २; २७, २; ३; ६. १३, ३; १८. १, ३१.

मनः १. ११, ६; २१, ४; २७, २; २. १२, २; ३; ३०, १; ४; ३. ४, ४; १८, ६; ४. १५, १५; ३८, ६; ५. १०, ८; ३०, १३; ६. ८, २; ३; १८, २^{२}; ४५, १; ६४, ३; ७०, १^{२}; २^{२}; ३^{२}; ७१, २; ८९, २^{२}; १०२, १; २^{२}; १०५, १; १११, २; ७. १३, ४^{२}; ३७, १; ८. १, ३; ७; २, ३; ९. ४, १९; १४, १८; १०. २, १९; २७; ७, ३७; ११. ७, २४; १०, ४; २६; १२. ४, ३०; १३. १, १९; १४. १, १०; १५. २, ६; १४; २०; २६; १४, १; १८. १, ३; १५; १६; १९; २, २१; २३; २४; ३, ९; ४, ६६; १९. ९, ४; २८, २; ४३, ४; ५२, ४; ५३, ७; २०. ५, ७; १७, २; १९, २; ५८, २; ६०, १; ९६, २४; ११३, २.

मनःऽकम् ६. १८, ३.

मनःऽकेतैः ६. १०५, १.

मनःऽजवाः ६. ९२, १.

मनःऽजुवा २०. ३६, ६.

मनःऽतेजाः १०. ५, २८.

मनःऽपाप ६. ४५, १.

मनःऽमुहः २. २, ५.

मनःऽयुजा ५. ७, ५; १०, ८; ६. ६५, १.

मनःऽषष्ठानि १९. ९, ५.

मनःऽहनम् ५. २९, १०.

मनःऽहा १६. १, ३.

मनन्त २०. ९१, २.

मनवः ६. १९, १; १९. २६, २.

मनवते १८. १, ३४.

मनवे १८. १, २०; २०. ११, ४; १७, ४; ८; ६१, २.

मनसः २. ३५, ४; ५. ३, ४; ६, ९; ६. ७४, २; १०५, १; ७. १०२, ८; ८. ३, १२; ९. २, २; १०. ५, ४८; १४. १, ५७; १८. १, १४; १९. ६, ७; ४०, १; ५२, १; ५६, ५.

मनसः २०. ९६, २४.

मनसा १. १, २; २. ३४, ३; ३५, ५; ३. ६, ८; ८, ६; २०, ९; २१, ५; ४. २१, ५; ३९, १०; ५. ६, १०; ११, १; २१, २; ३०, ६; ६. ५३, ३; ८३, ४^{२}; ९३, २; ९४, २; ९६, ३; ११९, ३; १२२, ४; ७. १, १; २, १; ५, ३; ५; ५४, २^{२}; ७३, १; ७७, ८; १०२, २; ८. ४, ८; १५, २; ९. ४, १०; १४, ६; ८; १५, ५; १५; १७; १०. ८, १४; ११. १, २३; ११, ८; १२. १, १४; २, ५२; ४, ३१; १३. १, १०; १३; ३, १९; १४. १, ९; ५६; ५७; २, ६; १५. १४, २; १८. २, २१; १९. २५, १; ५८, ५; २०. ३५, २; ८३, २; ८७, २; ९१, ८; ९६, ३.

मनसि ६. ७३, २; १०. ८, २८; १८. १, ३; १९. ४, २.

मनसे ६. ४१, १.

मनस्सयम् १४. १, १२.

मनस्वान् २०. ३४, १.

मनांसि ३. ८, ५; ६; ६. ६४, १; ७४, १; ९४, १; २; १४. १, ३२.

मनीषया १८. ४, ५८; २०. १३, ३.

मनीषा २०. ३५, २; ७६, ३.
मनीषाः २०. ७६, ४.
मनीषाम् ५. ९, ८; १९. ४२, ३.
मनीषिणः ३. ५, ६; ९. ४, ८; १५, २७; ११. ८, १३; १२. १, ८.
मनीषिणा ८. ५, ८.
मनीषिणे २०. २७, २.
मनीषी ८. ५, ३.
मनुः ७. ८७, ६; ८. १३, १०.
मनुऽजातेन ७. ३८, १.
मनुना ३. ९, २; १४. २, ४१.
मनुषः ५. १२, १; ७; १८. १, २२; २०. ३३, ३.
मनुष्यऽइषवः १. १९, २.
मनुष्यऽएनसानि ६. ११३, ३.
मनुष्यऽजाः ११. ६, १६; १२. ४, ४३; १४. २, ३.
मनुष्याः ३. ४, ६; ५. १७, १०; ६. ५१, ३; १४१, ३; ८. १, ११; ७, २६; १२, ७; १३, ९; १२; ९. १२, १६; १५, २७; १०. ६, ३२; ८, ३४; ९, ९; १०, २६; ३४; ११. ९, २७; १२. १, २२; २, १७; १४. २, ३८.
मनुष्याणाम् ६. ८६, ३; १२. २, ४४.
मनुष्यान् ४. २६, ४; ८. ९, २३; २४; १२, ७; १३, ९; १५. १४, १५.
मनुष्येभ्यः ८. १२, ८; १६. ४, ४.
मनुष्येषु ३. २२, ३; ४. ११, ३; ६. ११३, १; १९. ३, ३.
मनुष्यैः ६. ७१, २.
मनुष्वत् ५. १२, ८.
मनोः १९. ११, ५; २०. ६४, ३.
मन्त्रः ६. ६४, २; १५. २, १३.
मन्त्रम् ५. २०, ११; २०. ५९, ४.
मन्त्रयन्ते ९. १४, १०.
मन्त्रयामहे ९. १३, १; २; ३; ४; ५; ६; ७; ८; ९.
मन्त्रयेते इति ४. १६, २.
मन्त्राः १८. १, ६०.
मन्थ १९. २९, ५[४].
मन्थः २०. १२६, १५.
मन्थतु ८. ८, १.
मन्थन्तु ११. १, १.
मन्थम् २. २९, ६; १८. ४, ४२.
मन्थिता ८. ८, १.
मन्थे ५. २९, ७.
मन्थेन १०. ६, २.
मन्दतु २०. ८, १; ११७, १.
मन्दध्यै २०. ७७, २.
मन्दन्तु २०. २२, ३; ९३, १.
मन्दयत्ऽसखम् २०. ६८, ७.
मन्दसानः २०. ७५, २.
मन्दसाना १४. २, ६; २०. १३, १.
मन्दसे २०. १११, १; २.
मन्दस्व १६. ७, १२; २०. २३, ६.
मन्दानः २०. ५३, १; ५७, ११; ६१, २.
मन्दानम् २०. ९, १; ४९, ४.
मन्दिनः २०. १७, ४; १३७, ४.
मन्दिनम् २०. ३१, १.
मन्दिने २०. ७१, ८.
मन्दिऽभिः २०. ७१, ९.
मन्दिम् २०. ७१, ८.
मन्दू इति २०. ४०, १; ७०, ३.
मन्द्रः १८. १, ३०.
मन्द्रऽजिह्वम् २०. ८८, १.
मन्द्रा १२. १, ५७.

मन्द्रासु ५. २७, ६.
मन्द्रैः ७. १२२, १.
मन्मं २०. ३२, १; ७२, ३; ७७, २; ११९, १.
मन्मना २०. ११५, २.
मन्मनि १८. १, ३६.
मन्महे ४. २४, १^{२}; २५, १; १०. ४, ११.
मन्मानि ५. १२, २.
मन्यः २. १२, ७.
मन्यताम् ४. ८, १; ५. २८, ११; ७. २१, १; ३; १८. ३, ६९; ४, २६; ४३.
मन्यते २. १२, ६; ४. १६, १; २०, ९; ५. १८, ४; ७; १९, ९; १२. ४, ६.
मन्यते ११. १०, ३२; १४. १, ३; २०. १२६, ९.
मन्यन्ताम् १. ३५, ४; ८. २, २१; ९. ४, २०.
मन्यन्ते १०. ७, २१.
मन्यमानः २. ३५, ३; ३. १६, २; ५. १८, ५; १९, ६; १२. ४, ३७; ३८.
मन्यमानस्य २०. ७३, २.
मन्यमाना ८. ९, २२.
मन्यमानान् २०. ८७, ४.
मन्यवे १. १०, २; १२. ४, १२; ५१; १८. ४, ८२; २०. १०५, २; १०७, १.
मन्यसे २०. ११२, २.
मन्यस्व ६. १३१, २.
मन्याः ६. २५, १.
मन्युः ४. ३१, ७; ३२, २^{४}; ६. ४०, २; ६५, १; ११६, ३; ७. ७८, ३; ९. १२, १३; ११. १०, १.
मन्युतः २. ७, २.
मन्युना ५. १८, ९; ७. ७३, ४; ५; ९८, १; १२. २, ५; १५. १४, २०.
मन्युम् १. २१, ३; ५. ३, २; ६. ४२, १; २^{२}; ३; १५. १४, १९.
मन्युऽमत् ८. ४, ३.
मन्युमत्ऽतमाः ७. २३, २.
मन्युऽमन्तम् १९. ४०, १.
मन्युऽशर्मनः ६. ४३, १; २.
मन्यै ३. १३, ६.
मन्ये ४. ३६, ९; ७. ४६, १; ७६, १^{२}; १०. ८, १६; २०. ६७, ३.
मन्येत १०. ८, २०; ११. १०, ७.
मन्यो इति ४. ३२, ६.
मन्यो इति ४. ३१, १; २; ३; ४; ५; ६; ३२, १; २; ३; ४; ५; ९. २, २३.
मन्योः १. १०, १; ५. १३, ६; ६. ४३, १; ८. ३; १२; १०. ५, ४८.
मन्वीत १२. ४, ४८.
मन्वे ४. २६, १; २८, १; २९, १.
मन्वे ४. २३, १; २७, १.
मर्म १. ६, ३; १२, ४; १९, २; ३; ४; ३४, २^{२}; ३. ८, ६^{३}; १८, ४; २५, ५^{२}; ६; ४. ३०, ७; ३६, ८; ५. ३, १; ३^{२}; ४; ७, २; ८, ३; २३, २; ६. ९, २^{३}; ३७, १; ४२, ३; ४३, ३; ६५, ३; ९४, २^{३}; १३०, ३; १३९, १; ७. २१, १; ३८, १^{२}; ३९, ४; ५२, २; ८. ७, ७; १९; ९. २, १; ४; ५; ७^{२}; ९; १०; ११; १६; १७; १८; ४, १२; १०. ३, १५; ८, २५; १२. ३, ४७; १३. १, २८; १४. १, ५२; १८. २, ३७^{२}; ४, ४९; १९. ८, १; १५, ६; ४९, ७; ५७, ३; २०. ३, १; १८, ५; २४, ३; ३८, १; ४७, ७; ८९, ३; १०४, १; ११५, ३; १४०, ३.
ममत्तन ७. ७५, १.

ममत्तु १०. ११७, २.

ममदत् ७. १९, ४.

ममद्धि १०. ३२, ३.

ममऽसत्येषु १०. ८९, ४.

ममार्थ १०. ९, २६.

ममाद् १०. ९५, १.

ममार ९. १९, ९; १८. ३, १३.

ममार १०. ८, ३२.

ममृजे ६. ११३, १.

ममे १०. २, २०; २१; १०. १५, ५; ४२, १.

मम्रुषः ६. १८, २.

मर्यः १. १३, २; २६, ४; ६. ५७, ३; १४. १, ४६; १९. २, ५.

मयःऽभुवः १. ५, १; ७. ६२, २.

मयःऽभुवा २. ४, ४.

मयःऽभूः ५. १७, १; ७. ११, १; १९. ४६, ६.

मयःऽभून् १८. १, ६.

मया ३. ५, ८; १४, ५; ६; ४. ३०, ४; ७. ६२, ७; १४. १, ४८; ५०; ५२; १९. ७१, १.

मयि १. १, २[२]; ३[२]; २. १२, १; २६, ४; ३. ५, २[२]; १०, ६; १४, २; ४; २२, ५; ५. ३, ५[३]; ६. ६९, १; ३[२]; ७३, २; ३; १०२, २; १०८, ३; १३९, २; ७. १३, ४; २०, १; ८४, २[२]; ८७, २[४]; ९४, ४; ९. १, १८; १०. ६, ३३; ११. ६, २६; ९, ३; ५; १२; १४; १२. २, ३३; १४. १, ५७; १६. १, १३; ९, ४; १७. १, ३०; १८. २, ५२; ३, ६१; १९. ३१, ६; १२.

मयूखाः १०. ७, ४४.

मयूरऽरोमऽभिः ७. १२२, १.

मयूर्यः ७. ५८, ७.

मरते १०. १२६, ११.

मरिष्यतः ११. ४, १३.

मरिष्यति ११. ४, १; ४; ५.

मरिष्यसि ५. ३०, ८; ८. २, २४[२]; ११. ४, १२; १८.

मरीचयः ५. २१, १०.

मरीचीः ४. ३८, ५; ६. ११३, २.

मरीमृशम् ८. ६, १७.

मरुतः १. २६, ३; ७. ८२, १; १०. १, २.

मरुतः २. २९, ५; ३. १, ६; ३, १; ४, ४; १२, ४; १९, ६; ४. ११, ४; २७, २; ३; ४; ५; ७; ५. ३, ३; २४, ६; ६. ३, १; ४, २; २२, ३; ३०, १; ४७, २; ९२, १; ७. २५, १; ३४, १; ८२, ३; ८. १, २; ९. १२, ३; १०. ९, ८; १०; ११. १, ३३; ११, २५; १३. ३, २३; १४. १, ३३; ५४; १८. २, २२; १९. १०, ९; १३, ९; ४५, १०; २०. २, १.

मरुतः १. २०, १; २. १२, ६; ३. १, २; २, ६; ४. १५, ५; २७, ६; ५. २१, ११; २६, ५; ६. २२, २[२]; ९३, ३; १३०, ४; ७. ८२, २; ८. ४, १८; १३. १, ३[२]; २०. १३, २; ६७, २.

मरुताम् ४. १३, ४; १५, १५; २७, १; ५. २४, १२; ६. १२५, ३; ७. ५२, ३; ९. १, ३; १०; ४, ८; १९. १३, १०.

मरुत्ऽभिः २. २९, ४; ३. १७, ९; ४. १५, ७; ८; ९; ६. ७४, ३; ७. १०३, १; २०. ६३, २; १२४, ५.

मरुत्वते ७. ५९, २.

मरुत्वन् ४. ३१, १.

मरुत्ऽवन्तम् १९. १८, ८.

मरुत्वान् ६. १०४, ३; १२२, ५; ११. १, २७; १२. ३, २४; १८. ३, २५.
मरुत्ऽवान् १९. १७, ८.
मरुत्ऽसखा २०. १२६, ९.
मरुत्ऽसु २०. १११, १.
मरै २०. ११२, २.
मर्चयता ८. २, १७.
मर्चयसि १३. १, ४०.
मर्जयन्त २०. ३५, २.
मर्तः ७. ८२, २; ९. ३, २०; १८. १, २४.
मर्तम् २०. ६३, ५.
मर्तस्य ४. २१, ४.
मर्ताः २०. ६९, ८.
मर्तान् ८. ३, २०; १८. १, २९; २०. १२, ५.
मर्ताय २०. ६३, ४.
मर्तासः १२. १, २०; १८. ३, २३.
मर्त्य १८. ३, १.
मर्त्यः ६. ४९, १; १२. २, ३८; ४, २१; १८. ४, ३७; १९. ४९, ९; २०. २५, १; २७, ४; ५०, १.
मर्त्यम् ११. १०, १३; १८; २०. ७५, २.
मर्त्यस्य ७. १२०, ३; १०. ८, २६; १२. २, ३६; १८. १, ३.
मर्त्याः ८. ५, १३; ९. २, १९; १२. १, १५; २२; ४१.
मर्त्यान् ४. ३७, १२; ६. ४१, ३; ९. १५, ७; १९. ५६, १.
मर्त्यानाम् ११. १, ५; १८. ३, १३.
मर्त्याय १८. ३, ४३.
मर्त्येन ९. १५, ८; १६.
मर्त्येभ्यः १२. १, १५; १८. २, ३३; २०. १४२, १.
मर्त्येषु ५. १८, १३; ९. १, ४; १२. २, ३३; १६. ४, २; १९. २६, १; ५९, १.
मर्म १२. १, ३५; २०. ३५, ६.
मर्माणि ५. ८, ९; ८. ३, १७; ८, २०.
मर्मन् ८. ३, १४.
मर्माणि ७. १२३, १.
मर्माविधम् ११. १२, २६.
मर्मृजत् २०. ३१, ४.
मर्मृज्यन्ते ४. ८, ७.
मर्यः २०. १०७, १५.
मर्यःऽइव १४. २, ३७; १८. ४, ६०.
मर्यम् २०. १७, १.
मर्याः २०. २६, ६; ४७, १२; ६९, ११.
मर्यादम् ५. १, ८.
मर्यादाः ५. १, ६.
मर्यादे ६. ८१, २.
मर्याऽधीरेभ्यः ५. ३१, १०.
मलगःऽईव १२. ३, २१.
मलम् ७. ९४, ३; १०. ५, २४; १२. २, २०; १४. २, ६७; ६८; ६९.
मलम्ऽइव २. ७, १.
मलात्ऽइव ६. ११५, ३.
मलिम्लुः १९. ४९, १०.
मलिम्लुचम् ८. ६, २.
मल्वः ४. ३६, १०; ५. १८, ७.
मल्वम् १२. १, ४८.
मशकऽजम्भनी ७. ५८, २.
मशकस्य ७. ५८, ३.
मशकाः ११. ३, ५.
मशकाःऽइव ४. ३६, ९.
मष्मषा ५. २३, ८.
मस्तिष्कः ९. १२, २.
मस्तिष्कम् १०. २, ८.

मस्तिष्कात् २. ३३, १; १०. २, २६; २०. ९६, १७.
महऽउन्माना ५. ७, ९.
महऽऋषयः १९. ९, ११.
महः ४. २५, ५; ६. ८०, १; ३; ९. ५, २४; १०. ६, ४; १२; ११. ६, ५; ९, २२; १३. ८, ५; १८. २, १६; २०. १७, ७.
मह: ४. १, ६; ५. २, ८; ६. ९२, ३; ७. २७, ८; १०. ७, २; १८. १, २; ५३; २०. ११, ६; ३५, ७; ४४, ३; ५८, ३; ७०, ६; ८८, ४; ९०, ३; ९२, १७; ९८, २; १००, १; १०४, ४; १०५, ५; १०७, ११.
महत् १. २०, ३; २१, ४; ३२, १; २. ३, ३; ५; ३. २९, ६; ८; ४. ८, ३; १९, ६; ५. १, ५; ९. १, २; १०. ७, ३८; ८, ६; १५; २०; ३३; ३७; ३८; ११. १०, ३; १६; १२. १, १८; ४, ३९; १५. १, ३; १९. ७, ५; २०. २०, ५; ५७, ८.
महतः १. १०, ४; ६. ७१, ३; ८. ८, ८; १०. ८, ९; १२. ११, ११; १३. १, २६; २, २९; २०. ८७, ४; ९१, १२.
महता २. ३१, ३; ५. ३१, १२; ६. ६६, १; ८. ४, १६; ९. २, १; ११. १, १९; १३. १, ८; २०. ९४, १; ११६, २.
महताम् ९. ४, ४; १९. ३३, २.
महति ३. ६, ३; ११. १०, २; ६.
महती ५. ७, ९; १२. १, १८.
महतीम् ११. १२, १५.
महते २. ६, २; ३. १२, २; ४. ८, ७; ५. २८, १४; ७. १७, १; ७७, ८; १०; ९. १५, ५; ११. १, ३; ७; १७. १, ९.
महत्ऽकाण्डाय १९. २३, १८.
महत्ऽसु २०. ५६, १.
महय २०. १२, १.
महऽयते २०. ८२, २.
महयन्तः २०. १०, २; ५९, २.
महयन्तु ४. १५, २; ३.
महयामसि २०. १९, ४.
महसा ६. १४२, १; १०. ६, २४; १४. २, ४३.
महस्वन्तम् ४. २५, ६.
महाऽआस्येभ्यः ११. २, ३०.
महाऽइन्द्रः १३. ४, २; ३; ४; ५; ६; ७; ९; १७. १, १८.
महाऽऋषभस्य ४. १५, १; ५.
महांसि ७. ७७, १०.
महाऽगणेभ्यः १९. २२, १७.
महाऽदेवः ५. २१, ११; ९. १२, ७; १२. ७, ८; १३. ४, ४; १५. १, ४; ५, १३.
महाऽदेवम् १५. ५, १२.
महाऽधनस्य ४. ३१, ६.
महाऽधने २०. ७०, ११.
महान् १. २०, ४; ४. १, ४; ५. २, ९; ८. ८, ८; ९. १, ४; २, १९; २०; २१; २२; २३; २४; ११. ३, २२; १२. १, १८[२]; १३. २, १४; २९[४]; १५. १, ४; २०. ५३, २; ५७, १२; ५८, ३[३]; ४[२]; ६२, ६; ६८, १०; ७१, १; ७; ९३, २; १०७, १२; १३८, १.
महाऽनद्याः १४. १, ३६.
महाऽनाम्नीः ११. ९, ६.
महानि २०. ११, ६.
महान्तः ३. १०, ४; ८. ९, ११; १९. ३६, ३.
महान्तम् ४. १९, १६; ११. २, २९.

महान्ति ९. ५, १; १०. ४, २३.
महाबुध्नःऽइव १. १४, १.
महाम् २०. १५, ६; ७०, २; ९५, १.
महाऽमनसाम् १९. १३, १०.
महाऽयमः १३. ४, ५.
महाऽवृक्षाः ४. ३७, ४.
महाऽवृषाः ५. २२, ५.
महाऽवृषान् ५. २२, ४; ८.
महाऽव्रतम् ११. ९, ६.
महि ४. २२, ३; ५. ३, ७; ७. ३०, १; २; १२. ३, १४; १३. २, ३[२]; २०. ३४, १०; ७७, ४; ९५, १.
महि २०. १४२, २.
महिऽत्वम् ७. ३०, १; १२. १, ५५; २०. ३५, ९; ७१, १; १२३, १.
महिऽत्वा ४. २, २; ४; ५; ५. ११, ३; ७. ८४, १; ८५, १; ८. ३, २४; ९, २; ९. १५, ३; ९; १२. ३, ५; १४. २, ३२; १९. ४९, १; २०. १२, ३; ३२, १; ७७, ५.
महिना २०. ८१, २; ९२, २१.
महिमा ६. ८०, ३; ११. ३, २२; १३. २, २९; ४५; ७, १६; १५. ७, १; १९. ३, २; ३; ३४, ५; २०. ९, ४; ४९, ७; ५८, ३; ७७, ५; १०४, २.
महिमानः ३. १०, ४; ७. ५, १; ८. ९, ११; १९. ६, ३.
महिमानम् ३. १०, १२; ५. २७, ५; ११. ३, २३; १७. १, १२; १८. ४, ८; १९. ५६, ३; २०. ३५, ८; ५०, १; ७३, २; ८७, ३; ९९, २.
महिम्ना ४. ३०, ८; ३५, ३; ६. ७१, ३; ११. १, १९; १३. १, ८.
महिम्ने ९. ३, २५; २६; २७; २८; २९; ३०; ३१.
महिऽवृधे २०. ७३, ३.
महिऽव्रतस्य १३. २, १.
महिव्रते इति महिऽव्रते ७. ११७, १; १४. २, ४५.
महिष २. ३५, ४.
महिषः ५. ३, ८; २६, २; ६. ३१, २; ७. १६, १; १२. ३, ३८; १३. २, ३०; ३२; ३३; ४२; ४३; ४४; १८. ३, ६५; २०. ४८, ५; ९५, १.
महिषम् २०. ९२, १२.
महिषी २. ३६, ३.
मही १. १७, २; २. ३१, १; ४. २, ४; ५. ७, १०; २५, २; २७, ९; ६. १७, १; २; ३; ४; ९. १५, १२; १०. ७, १४; ८, ३०; ११. १, ८; ९, २०; १०, १५; ११, ४; १४. १, २; १८. २, २५; १९. ५४, २[२]; २०. ३१, ५; ६०, ४; ७१, ४.
मही इति ४. १, ४[२]; ५. १, ५; १८. १, ३९.
महीऽइव ६. ६, ३.
महीः ३. १३, ४; ४. ८, ४; ८. ८, ५; १८. १, ४९; ४, ७; २०. ९, ४; ४९, ७; ५१, ४; ६३, ९; ९२, १९.
महीम् ६. ५४, १; ७. ६, २; ७, २; ८. ८, १३; १०. २, ७; ११. ६, ५; १७; १३. १, ४५; २०. ७५, २.
महीयते ५. १७, १५; २०. १२६, १०.
महीलुका १०. १०, ६.
महे १. ५, १; २. ५, ४; ५. ११, १; १०. ६, ८; १९. २४, २; ३; २०. २१, १; १०; २२, ३; २३, ६; ३०, १; ४७, १; ७३, ३; १३७, १२.

महेम **२०.** १३, ३.

मह्ना **९.** १५, ३; **१०.** २, १८; **१८.** ३, ६३; **२०.** ११, ७; ३४, १; ५८, ४; ९१, १२; ११८, ४.

मह्यार्नि **१०.** २, ६.

मह्यार्नम् **१०.** २, १२.

मह्यम् **१.** २९, ४; **२.** १२, २; **३.** ५, ६; ७; १५, १; २२, १; **४.** ३६, १०; ३९, १; ३; ५; ७; **५.** ३, १; ३; ४; १३, १; **६.** २४, १; ६१, १[४]; ६३, २; ७१, ३; ८२, ३; ८४, ३; ८९, ३[३]; **७.** ३९, ५; **९.** २, ७; ८; ११[३]; **१०.** ६, २; २९; **११.** १, २०; **१२.** १, १६; ३१; ३, ११; **१४.** १, ५०; ५२; २, ४; **१७.** १, ६; २४; **१९.** ८, ६; ३१, ६; ७१, १; **२०.** ८३, १.

मह्यै **३.** ५, ५; **८.** ५, २०.

मा **१.** १, ४; १९, १; २०, १[२]; ३०, १[२]; **२.** ६, २[२]; ७, ४[२]; १५, १; २; ३; ४; ५; ६; २८, १; ३[२]; २९, ४[२]; ७; **३.** ११, ६; १२, ६; १५, ५; ८; १९, ८; २५, १; २८, ५; ६; २९, ८[३]; ३०, ३[२]; ५; ३१, ८; ९; **४.** ७, ७; ८, २; १६, ७; २०, ५; ७; २१, ७[२]; ३४, ८; ३७, १२; ३८, ३; ३९, ९; **५.** २, ४; ३, ४; ६[२]; ७[३]; ८[२]; ६, २; ७, १[२]; २; ६[२]; ८, ३[२]; ४; ९, ८; ११, ७; ८; १३, ४; ५; १८, १; २; १९, ९; २२, ११[२]; २९, ११; ३०, १[२]; ६; ८; १४[२]; १५; १७; **६.** २७, ३; ३२, ३[२]; ४१, ३; ५१, ३; ५६, १; ५७, ३; ७३, ३; ८७, १; २; ११०, ३[२]; ११२, १; ११८, ३; १२०, २; १२३, ४; १२४, ३; १२७, १; १३४, २; १४०, २; ३; १४२, १; **७.** १२, १[२]; २१, ३; ३६, ३[२]; ५४, २[३]; ५५, २; ४; ५७, १; ६२, १; ४; ६; ७; ७१, १; ७३, २; ७९, १[२]; ८७, ३; १०४, १; १०७, १; ११३, १; १२२, १; **८.** १, ४[२]; ५; ७[४]; ८; ९[२]; १०[२]; ११; १२; १५; १६[३]; १८; १९[२]; २, १[२]; ५[२]; ७; १७; २३; २४; २६; ३, ९; १७; १८; ४, ७; २३; २४; ६, ३[३]; २०; २५[२]; ८, १९; २०; २१[२]; **९.** २, १०; ३, १६; २४; ४, २४; ५, ४[२]; **१०.** १, ७; १६; १७; २६; २९; ३१; ५, १५; १६; १७; १८; १९; २०; २१; २३; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ९, ७; ११; **११.** १, २२[२]; २५; ३२; २, १[४]; २[२]; ७; ८; १७; १९[२]; २०[३]; २१[२]; २६[३]; २९[६]; ६, २६; ११, १३; २०; २१; १२, ९; १४; १६; १९; **१२.** १, १८; २३; २४; २५; २८; ३१; ३२[४]; ३३; ३४; ३५[२]; ४६; २, १०; १८; २३; ३३[२]; ३, १४; १७; १८[२]; २२; २३; ४३; ४६[३]; ४, ५२; **१३.** १, १२; ५९[३]; २, ५; ३७; **१४.** १, २२; ४८; ६३; २, ९; ११; १६; १९; ५०; ६९[५]; **१६.** १, ४; २, ५; ३, २[२]; ३[२]; ४; ४, ३; ५[२]; ७, १३; ८, ३; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३२; **१७.** १, ६; ८; २४; २८[२]; २९[२]; **१८.** १, ५२; २, ४[४]; २४[५]; २५[२]; ३१; ३६[२]; ३, ९; ५०; ५३; ६४; ७३; ४, १२; १३; ३०; **१९.** १५, २; २०, ४; २७, ५; ६[३]; ८[२]; ३३, ५;

४०, २^{२}; ३^{३}; ४६, २; ४७, ६^{२}; ७^{२}; ५५, १; २; ५७, ३; ५८, ४; २०. १३, ३; १८, ५; २१, ३; २२, २^{२}; २३, ८; ३७, ७; ५५, ३; ५७, ३; ६७, २; ६८, ३; ६९, ८; ७९, २^{२}; ८५, १^{२}; ९६, १; १०७, ७; ११६, १; १४३, ५.

मा १. ३३, ४; २. ४, ५; १२, ५^{२}; १६, १; २; ३; ४; ५; ३. ५, १; ५; १०, ७; १३, ५; ६^{२}; १५, २; ४; २०, १०; २२, २; २५, ४; ४. १९, ८^{२}; २०, ६; २४, १; २६, ७; ३०, २; ३६, ९; ५. ३, ४; ९, ८^{२}; १०, १; २; ३; ४; ५; ६; ७; ११, ८; २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २८, २; १४; २९, ६; ७; ८; ९; ६. १९, १^{२}; २; २६, १^{२}; ३९, १; ४८, १; २; ३; ५५, १; ५८, १^{२}; ६९, २; ७१, २; ९६, २; ९९, ३; १०७, १; २; ३; ४; ११५, २; ३; ११९, ३; १२९, १^{२}; २; ३; ७. १३, १^{२}; १४, २; ३४, १^{२}; ५२, ९; ५७, १; ६६, १; २; ६९, १; ७९, २; ८६, ३; ९४, १; २; १०२, ४; १०७, १; २; १२०, २; ८. ४, ७; ८; ११; १५; १६; ५, २०; ६, १; ७, १३; ९. १, १४; १५; १९; २४; १४, २२; १५, १५; १०. १, १०; ३, १०; १७^{२}; १८^{२}; १९^{२}; २०^{२}; २१^{२}; २२^{२}; २३^{२}; २४^{२}; २५^{२}; ५, ६; २२; ४६; ४७; ६, २; २२; २३; २४^{२}; २५; २६; २७; २८; ३१; ३२; ११. ८, ७^{२}; १२. १, २१; २२; २३; २४; ३०; ४१; ५८; ६३^{२}; २, ४०; ३, १७; ४, ३७; १३. १, १२; १३; १४; ५७; ८, ३; ५; ६; ९, १; २; ४; १६. १, १२; २, ५; ३, २^{२}; ३^{२}; ४^{३}; ४, ४; ५; ७; ९, २; १७. १, ६^{२}; ७^{३}; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; २५; २६; २८; २९; ३०; १८. १, ८; ३, १०^{२}; ११; १२^{२}; २५; २६; २७; २८; ३८; ५६; १९. १६, १^{२}; २^{२}; १७, १^{३}; २^{३}; ३^{३}; ४^{३}; ५^{३}; ६^{३}; ७^{३}; ८^{३}; ९^{३}; १०^{३}; १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०; २०, ४; २७, १४^{२}; १५^{२}; ३१, २; ७^{२}; १२; १३^{२}; ३२, ८; ३५, ४^{५}; ४३, १; २; ३; ४; ५; ६; ७^{२}; ८; ४४, ६; ४५, ६; ७; ८; ९; १०; ५२, ४; ६२, १^{२}; ७२, १; २०. ७६, ३; ८९, ३; १३९, ५.

मांसम् ४. १२, ४; ५. २९, ५; १५; ६. ७०, १; ८. ६, २३; ९. ८, ९; ९, ७; १०. २, १; ९, १८; ११. १०, ११; १२; १८. ४, ४२.

मांसऽवान् १८. ४, २०.

मांसस्यं ४. १२, ३.

मांसानि २. २४, १; २; ३; ४; ५; ६; ७; ८; ११. ३, ७; १२. ११, ८.

मांसे १. ११, ४; ४. १७, ४; ५. ३१, १.

मांसेन ४. १२, ४.

मांस्त ११. २, ८.

माकिः १८. १, २५; १९. ४७, ६.

माकीम् २०. २२, २.

मागधः १५. २, ५; १३; १९; २५.

मार्तः १९. ४८, २.

मातः १२. १, ६३.

मातरः १. ५, २; ६. ५१, २; ९, ३; १९. ४०, ३; २०. २३, ५.

मातरम् १. २, १; ११, ५; ४. १८, २; ५.

२, ६; ६. ३१, १; ११०, ३; ११२, २; १२०, १; १४०, १; २; ३; ७. १, २; ६, २; ७, २; ९. ५, ३०; ११. २, २९; १२. १, १७; १८. ३, ४९; २०. ४८, ४; १०७, ९.

मातरा ५. १, ४; २०. १०५, २.

मातरि ११. ९, ६.

मातरिभ्वरी इति ५. २, ९; २०. १०७, १२.

मातरिश्वन् ११. ७, १३.

मातरिश्वनः १९. २७, ४.

मातरिश्वना ५. १०, ८.

मातरिश्वा ५. १७, १; ८. १, ५; १०. ७, २; ४; ८, ३९; ४०; ९, २६; १२. १, ५१; १३. ३, १९; १४. १, ५४; १५. २, ७; १४; २०; २७; १६. ३, ४; १९. २०, २.

मातरिश्वानम् ९. १५, २८; ११. ६, १५.

मातली ८. ९, ५; ११. ८, २३; १८. १, ४७.

मातवै ९. १५, ६.

माता १. २४, ३; २. २८, ४; ३. ९, १; २३, ३; ६; ४. ५, ६; ५. ५, १; १३, ७; ३०, ५; ६. १६, २; ४६, १; १२०, २; ७. ६, १; ७८, १; ८. ६, १; ७, २; ९. १, ४; ५; १४, ८; ९; १५, १२; १०. ३, ८; १०, १८[2]; १२. १, १०; १२; ३, ५; ४, ३३; १४. २, ३७; १८. १, ५३; २, ५०; ३, ५०; १९. ४, २; ३९, ३; ४९, ५; २०. ८७, ३; १०८, २.

माताऽइव २. २८, १; ५; ५. २६, ५; ६. ३०, ३.

मातुः १. १४, २; ३. २५, ५; ६. ११६, २; ३; ७. २, १; ८. ९, ५; ९. १५, १०; १२. ४, ३२; १४. २, २५; १८. २, ५२; २०. ३५, ७.

मातृऽकृतात् ५. ३०, ४.

मातृऽबन्धु १२. ९, ५.

मातृमत्ऽभ्यः १२. १, ६०.

मातृः ९. १४, १०.

मातृऽभ्यः ३. १०, १०; १९. २७, २; ३७, ४.

मात्रया ९. १५, १९.

मात्रा ८. ९, ५; ११. १, ६.

मात्रा ३. ३०, २.

मात्राः ३. २४, ६.

मात्राम् १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५.

मात्रायाः ८. ९, ५.

मात्रे १. ३१, ४; २०. ९२, १२.

मात्रे इति २०. ७६, ६.

मादय ५. ८, १; ६. १३०, ४[2].

मादयत ६. १३०, ४.

मादयध्यै २०. ३६, ३.

मादयध्वम् २०. १३, २.

मादयध्वम् ५. ३, ६; ९. २, ८; १८. १, ४२; ३, २०; ४, ४६; ६४.

मादयन्ताम् १८. ३, ५३; १९. ५८, ६.

मादयन्तु २०. १२, ५.

मादयन्ते १८. १, ३५; २, ३५.

मादयसे २०. १२०, २.

मादयस्व २०. १३, ४; ५६, ५.

मादयस्व १८. १, ५९; ६०; २०. १२, ५; २५, ७; ३३, २.

मादयाथः ४. २५, ६.

मादयिष्णवः ७. ८२, ३.

मादयेथाम् ७. ६०, २.

माध्यंदिनस्य ७. ७६, १.

माध्यंन्दिने ७. ८१, २; २०. १२, ७.
माध्वी इति ७. ७७, ४.
मानयेत् १५. १०, २.
मानवाः ३. २१, ५; ११. १२, २; १२. १, १५; १८. ४, ५९.
मानवानाम् ४. २२, ५; १२. १, २.
मानवी २०. १२६, २३.
मानवीः ३. २४, ३.
मानवेर्भ्यः ५. १७, ९.
मानस्य ३. १२, ५; ९. ३, ५; ६; २१.
मानस्य ९. ३, ९.
मानुषः ४. १६, ८; १२. ४, २०.
मानुषाः ६. २३, ३; १८. ३, ३८.
मानुषाणाम् ४. १४, ५; ३०, ३; ७. ११६, १.
मानुषान् २०. १३९, २.
मानुषासः ७. ८२, ३.
मानुषीः ४. ३२, २; १३. २, २०; १७. १, २८; २०. ४७, १७.
मानुषीणाम् २०. ११, २.
मानुषीभिः ७. ८९, १.
मानुषीषु ५. ११, ८; ९.
मानुषे ८. ५, १४.
मानुषेषु ४. २८, ५.
माम् १. ३४, ४; ५; २. ७, ४; २७, ७; ३०, १; ३. ६, १; ३; ५; १८, ६; २२, ३; ६; ४. ३०, ४; ६. ८, १[2]; २; ३; ९, १; ८२, २; ८९, २; १०२, १; १०८, ४; १२४, १; १३०, १; २; ३; ४; १३१, १; २; १३३, ५; १३९, २; ३; ४; ७. १२, ३; ३७, १; ८४, २; १०. ६, ३१; ११. ३, ३०; १२. ३, १२; १३. १, ५७; ५८; १६. ४, ३; १८. ३, १०; ११; १९. ५२, ४; २०. १२६, ९.
मामकम् १. २९, ५; ३. २४, १; ४. ४, २; १८. ३, ५६.
मामकान् ३. ६, १; ५; ४. ३७, १०; १३. १, ३०.
मामऽपश्यम् ७. ३९, १.
मायया ४. ३८, ३; ६. ७२, १; ७. ८६, १; ८. ४, २४; १०. ८, ३४; १३. २, ३; ११; १४. १, २३; १९. ६८, १; २०. ३६, ६.
माया ८. ९, ५.
मायाः ४. २३, ५; ८. ३, २४; २०. ३६, ९; ८७, ५.
मायाभिः १२. १, ८; २०. ११, ६; २९, ४.
मायाम् २. २९, ६; ८. १३, ३; ४.
मायायाः ८. ९, ५[2].
मायिनः १९. २७, ५; ६; ६६, १.
मायिनम् २०. २१, ७.
मायिनाम् २०. ११, ३.
मायी ५. ११, ४.
मायुम् ९. १, ८; १५, ६; ७; १९. ४९, ४.
मायू इति १८. ४, ४.
माये ८. १३, १.
मायौ ६. ३८, ४.
मारयति १३. ३, ३.
मारयन्ति ८. ६, १९.
मारयाति ८. ६, १८.
मारुतः १३. ४, ८.
मारुतम् ४. २७, ७; १५. १४, १; २०. १०६, ३.
मारुताः ४. १५, ४.
मारुतेन ४. २७, ६.
मार्तऽवत्सम् ८. ६, २६.
मार्त्यवः ८. १३, ७.

मार्ष्टु ४. १८, ७; ६. ५३, ३; १०. ९, ३.
माऽर्वते २०. ६०, ५; ७१, ५.
मार्षऽआज्यम् १२. २, ४.
मार्षम् ६. १४०, २.
मार्षाः १२. २, ५३.
मासः ५. ६, ४; १४. १, ४.
मासः ८. ९, १७.
मासम् १३. ३, ८.
मासाः ४. ३५, ४; १०. ७, ५; ११. ९, २०; १५. ६, १७.
मासातै १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५.
मासान् ३. १०, ९; ११. ८, १७.
मासानाम् १५. ६, १८; १६. ८, २२.
मासाम् १. ३५, ४.
मासाय १३. २, १२.
मासि ५. २५, १०; ११; १२; १३; ८. १२, ३; ४; १८. १, ३५; ४, ६३.
मासौ १५. ४, २; ३; ५; ६; ८; ९; ११; १२; १४; १५; १७; १८.
माहिनाय २०. ३५, १.
मितः १८. ३, ५१.
मितयः १९. १०, ७.
मिता ८. ९, ४; ९. ३, ९; १६; १७; ११. १, ६.
मिताः १२. ३, ३०; १९. ४२, १.
मिताम् ९. ३, १९.
मित्र ४. २९, ५.
मित्रः १. ९, १; १८, २; २. ५, ३; २८, १; २; ३. ८, १; २२, २; ५. १७, २; ६. ४, २; १०३, १; ७. ३१, १; ९. ३, १८; ४, १२; १२, ७; २३; १०. ४, १६; ११. ७, १५; ११, २५; १३. ३, १३; १५. २, ५; १८. १, ३३; ३६; ३९; १९. ९, ६; ७; १९, १; ४४, १०; २०. १६, २; ७६, ४; १०६, ३.
मित्रःऽइव १९. ४९, २.
मित्रऽतूर्याय ५. २०, ७.
मित्रऽधा २. ६, ४.
मित्रम् १. ३, २; ३. २१, ८; ५. १९, १५; ८. ३, १; ९. १५, २८; ११. ८, २; १९. १५, ६.
मित्रऽमहः ५. १२, १.
मित्रऽराजन् २. २८, ५.
मित्रऽवर्धन ४. ८, २.
मित्रऽवर्धनः ४. ८, ६.
मित्रस्य ६. ८५, २; १२५, ३; १३. २, ३५; १८. १, ७; २०. १०७, १४; १२३, २.
मित्राः ११. ११, २; २६.
मित्राः २. २८, ३; ३. ३, ५; ६. ७, १.
मित्राणाम् ९. २, १४.
मित्राणि ११. ११, २.
मित्रात् १९. १५, ६.
मित्राय १२. ४, २६; १४. २, ४६.
मित्रावरुणयोः १०. ५, ११; ११. ४, १२; १६. ८, २८.
मित्रावरुणा ४. २९, ३; ४.
मित्रावरुणा ३. ४, ४; १६, १; ४. ३०, १, १४. १, ५४; १८. ३, १२.
मित्रावरुणा ६. ९७, २; ९. १५, २३; १९. ११, ६.
मित्रावरुणौ ४. २९, ६; १३. १, ३१.
मित्रावरुणौ ४. २९, ७; ५. २४, ५; २५, ४; ६. ८९, ३; १३२, ५; १३. १, २०; १६. ४, ७; १९. १०, ४.

मित्रावरुणौ १. २०, २; ३. २५, ६; ४. २९, १; ६. ३२, ३.
मित्रिणः ११. ११, २१.
मित्रियात् २. २८, १.
मित्रियेण ७. ६२, १; १४. २, १२.
मित्रेण २. ६, ४; ३. ६, २.
मित्रैः ५. २०, ८; १२. ३, ४८.
मिथः १. २८, ४; ३. ३०, ४; ५. १७, ७; ६. ३२, ३; ७. ८८, १; ८. ८, २१; २०. १६, १०.
मिथःऽअवद्यपेभिः २०. ९१, ८.
मिथःऽयोधः १२. ७, १३.
मिथुऽदृशा २०. ७४, ३.
मिथुनऽत्वम् ८. ९, १०.
मिथुनम् ६. १४१, २.
मिथुना ८. ३, १२; १०. ५, ४८; १४. २, ५; १८. १, १०; २, ३३; २०. २५, ३.
मिथुना १२. ३, २; ९.
मिथुनाः ८. ४, २३; २०. ७२, २; ७५, १.
मिथुनासः ९. १४, १३.
मिथुया ४. २९, ७; ३९, ९; ८. ४, १३.
मिनन्ति १८. १, ५.
मिनाति १४. १, ३३; १८. ४, ६०; २०. ३४, ५.
मिनीत् ६. ११०, ३.
मिनोति ४. १६, ५.
मिनोतु ३. १२, ४.
मिनोमि ३. १२, १.
मिमते ४. ३६, ५; ९. १५, २.
मिमाति ९. १, ८; १५, ६; ७.
मिमाथाम् २०. १४३, ६.
मिमानः ४. ३१, २; १०. ७, २; १३. २, २२; १९. ५६, १; २०. ४७, १९.
मिमानः १३. ३, १९.
मिमाना ५. १२, ७.
मिमाय ९. १५, २१.
मिमिक्षिरे २०. ३०, ३.
मिमिक्षुः २०. ३३, १.
मिमीते ४. ११, २; ५. २८, १; ९. १५, २; १०. ७, २; १८. ३, ४०.
मिमीमहे १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४.
मिमीयात् ६. ९२, ३; १८. १, १०.
मिमीष्व १३. १, २७.
मिमीहि २०. ३७, ११.
मिम्यक्ष २०. ९४, २.
मिश्रऽधान्ये ५. ३१, १.
मिश्रम् १२. ३, ४४.
मिश्राः ४. १४, २; १२. ३, ४१.
मिषता १०. ८, ३०.
मिषन्तम् ९. १५, ६.
मिषन्ति ५. ६, ३; १८. १, ९.
मीढुषः १३. २, १.
मीढ्वः १४. १, १८.
मीमांसमानस्य ९. ७, ७.
मीमांसमानाः ९. १, ३.
मीमांसितस्य ९. ७, ७.
मीमाय ५. ११, ३.
मीमृषः ३. १५, ४.
मीयन्ते ४. २४, ४; १२. १, १३.
मीयमाना ११. १, ६.
मुक्षत ५. २९, ११; ८. ३, १८.
मुखतः ११. ४, ४.
मुखम् २. ३५, ५; ४. ३, ३; ३४, १; ५. २३, १३; ६. ५०, १; ८. २, १७; १०. २, ६; ७, १९; २०; ९, १३; ११. १,

३१; ३, १; १०, १४; १५; **१२.** ३, ५१; ४, २०; **१३.** १, १३; २, ३९; **१९.** ६, ५; ६; ५७, ३; ५८, ५.

मुखस्य **७.** ११९, १.

मुखा **६.** १०६, २; **८.** ६, १५; **२०.** १३७, ३.

मुखात् **१९.** ६, ७.

मुखानि **७.** ५८, ४; **१०.** ९, १.

मुखाय **११.** २, ५.

मुखे **६.** ६, २; **१२.** ७, १४.

मुखेन **७.** ६६, २; **११.** ४, ४²; **१२.** ४, ५.

मुख्याम् **६.** ४३, ३.

मुग्धाः **७.** ५, ५.

मुचः **९.** ३, २४.

मुच्यताम् **१.** ३, ६; ७; ८; ९.

मुच्यते **१०.** १, ३२.

मुच्यते **४.** ३६, १०.

मुच्यन्ताम् **६.** ११२, ३.

मुच्यमानः **१२.** २, १२.

मुच्यसे **८.** ८, १६.

मुच्यातै **८.** ८, ६.

मुच्यातै **४.** १६, ४.

मुञ्च **१.** १२, ३; **२.** ९, १; **६.** ८४, २; **१९.** ४४, ८; ९.

मुञ्च **२.** ३५, ३; **६.** ११२, २²; **७.** ४, १; ८८, २²; ४; **८.** ६, २६; **९.** २, ३; **१३.** ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; **१८.** ४, ७०; **१९.** ४४, ४; **२०.** ९६, १.

मुञ्चतं **१.** ३१, २; **६.** ११४, २.

मुञ्चत **५.** १४, ३; **६.** ११४, १; ११५, १; **८.** ७, ५; **१४.** २, १६.

मुञ्चतः **८.** २, १८.

मुञ्चतम् **७.** ४३, २.

मुञ्चतम् **४.** २५, १; २; ३; ४; ५; ६; ७; २६, १; २; ३; ४; ५; ६; ७; २८, १; २; ३; ४; ५; ६; ७; २९, १; २; ३; ४; ५; ६; ७.

मुञ्चताम् **२.** ८, १; **३.** ७, ४; **६.** ११५, २; **७.** ८२, २; **१४.** २, ५९; ६०; ६१; ६२; **१९.** ४५, २; ५७, ५.

मुञ्चति **३.** २९, १.

मुञ्चतु **४.** २३, १; २; ३; ४; ५; ६; ७; २४, १; २; ३; ४; ५; ६; ७; **७.** ६६, २; ८८, १; **११.** ८, ७.

मुञ्चन्तः **२.** १०, ८.

मुञ्चन्तु **६.** २३, २; ९६, २; **७.** ११७, २; **८.** २, २७; **१०.** १, १२; **११.** ८, ७.

मुञ्चन्तु **३.** ७, ५; **४.** २७, १; २; ३; ४; ५; ६; ७; **६.** ९६, १; **७.** ८२, ३; ११७, १; **८.** ७, १३; **१०.** १, ११; **११.** ८, १; २; ३; ४; ५; ६; ८; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; **१४.** २, ४५.

मुञ्चात् **६.** १२३, १.

मुञ्चामि **१.** १०, ३; ४; **३.** ११, १; **२०.** ९६, ६.

मुञ्चामि **२.** १०, १; २; ३; ४; ५; ६; ७; ८; **५.** १३, ६; **६.** १८, ३; **७.** ८३, १; **९.** २, २; **१०.** ६, ३०; **१४.** १, १७; १८; १९; ५८.

मुञ्चासि **६.** १२१, ४.

मुञ्चे **१९.** ३१, १३.

मुञ्जः **१.** २, ४.

मुदीमहि **२०.** ११६, २.

मुद्गलम् **४.** २९, ६.

मुद्रम् **१८.** ३, १९.
मुनिऽकेशम् **८.** ६, १७.
मुनेः **७.** ७८, १.
मुमुक्तम् **५.** ६, ८.
मुमुक्तम् **३.** ११, १; **६.** ९७, २; **७.** ४२, १; **२०.** ९६, ६.
मुमुग्धि **६.** १११, १.
मुमुचः **२०.** २३, ८.
मुमुचानः **६.** ११५, ३.
मुमुचानाः **८.** ७, १६.
मुमोक्तु **२.** ३४, ३; ४.
मुरीय **८.** ४, १५.
मुषायत् **२०.** ३५, ७.
मुषायति **४.** २१, ३.
मुषिता **२०.** १६, १०.
मुष्कऽआबर्हः **३.** ९, २.
मुष्कयोः **६.** १३८, ४; ५.
मुष्करम् **६.** १४, २.
मुष्काभ्याम् **८.** ६, ५.
मुष्कौ **४.** ३७, ७; **६.** १२७, २.
मुष्टिः **६.** १२६, २.
मुष्टिऽहत्यया **२०.** ७०, १८.
मुष्टिऽहा **५.** २२, ४.
मुष्णाति **४.** ३४, ४.
मुसलम् **११.** ३, ३; **१२.** ३, १३.
मुसले **१०.** ९, २६.
मुहुः **११.** ७, ६; **१२.** २, ३८; ५२; **१८.** १, १०; **२०.** ८५, १.
मुह्यत **३.** २, ४.
मुह्यन्तु **६.** ६७, १; **११.** ११, १३; १२, २०.
मूजऽवतः **५.** २२, ७; ८.
मूजवत्ऽभ्यः **५.** २२, १४.
मूजऽवन्तः **५.** २२, ५.
मूढाः **६.** ६७, २; **११.** १२, २१.
मूत्रम् **१.** ३, ६; ७; ८; ९; **६.** ४४, ३; **९.** १३, १०.
मूरऽदेवाः **८.** ४, २४.
मूरऽदेवान् **८.** ३, २; १३; **१०.** ५, ४९.
मूरम् **१.** २८, ३; **४.** १७, ३.
मूराः **२०.** २२, २.
मूर्णाः **४.** ३, ६.
मूर्धतः **१०.** ६, ३१; ३२.
मूर्धन् **४.** ३०, ७.
मूर्धा **१६.** ३, १; २.
मूर्धानम् **३.** ६, ६; **९.** १२, १३; १५, ६; **१०.** २, २६; ७, ३२; **२०.** ९१, १२.
मूर्ध्नः **१९.** ६, १६.
मूलऽकृत् **४.** २८, ६.
मूलऽबर्हणात् **६.** ११०, २; ११२, १.
मूलऽबर्हणी **१२.** ८, ६.
मूलम् **२.** ७, ३; **३.** २३, ६; **६.** १४, २; १३७, ३; **८.** ३, १०; ७, २; १२; **१३.** १, ५६; ५७; **१९.** ७, ३.
मूलात् **६.** ४४, ३; **७.** ६१, १; **१२.** ११, २.
मूलानि **१२.** ९, ४.
मूलिनम् **५.** ३१, १२.
मूलेन **७.** ७८, १; **१९.** ३६, २.
मूलेभ्यः **६.** १३, ३.
मृक्ष्व **६.** ११२, ३; ११३, २.
मृगः **४.** ३, ६; **७.** २७, २; ८९, ३; **१०.** १, २६; ३, ६; **२०.** ५३, २; ५७, १२; १२६, ३; २२.
मृगम् **३.** १५, १; **२०.** ९२, १२.
मृगम्ऽइव **५.** १४, १२.
मृगयन्ते **४.** ३६, ३.
मृगयामहे **१०.** ५, ४२.

मृगऽयुः १०. १, २६.
मृगऽशिरः १९. ७, २.
मृगस्य ४. ३, ६.
मृगाः ५. २१, ४; ८. ७, २४; ११. २, २४; ८, ८; १२. १, ४९; १९. ३८, २.
मृगाणाम् २. ३६, ४; ३. २२, ६.
मृगाय १२. १, ४८.
मृगाखः ६. ५२, २.
मृगीऽइव ५. १४, ११.
मृगेषु ३. २१, २; १२. १, २५.
मृजानाः १८. ३, १७.
मृजे १६. ७, ८.
मृजेथाम् १८. ४, ४९.
मृज्मः ४. १७, ८.
मृज्महे १४. २, ६६.
मृज्महे ४. १७, ६; ७; १८, ८; ७. ६७, २; ३; १२. २, १३; १३. १, ५८.
मृड १८. १, ४०.
मृड १. १३, ४; ५. ३, ८; ४, ७; ६. ३०, ३; ५७, २; ११. २, ११; २८[२]; १२. १, ४६; ४७; १७. १, ८; ११; १९. ४४, ४; ५५, २.
मृडत १. २०, १; २६, ४; १८. ३, १६.
मृडत ३. २६, १; २; ३; ४; ५; ६.
मृडतम् ८. २, ७; ११. २, १.
मृडतम् ५. ६, ५; ६; ७.
मृडतात् ११. १, २०.
मृडन्तु ७. ११४, ७.
मृडय १. १३, २; २६, ४.
मृडयन्तु १०. १, २२.
मृडयासि ५. २२, ९; ६. २६, १.
मृडात् २. २, २.
मृडाति १. १२, १; ७. ११४, १.
मृडिता १०. १, २२; १२. ३, ९.
मृड्ढि ११. १, २९; ३१[२]; १८. ४, ५६.
मृड्ढम् १२. २, १९[२].
मृण १९. २९, ४[४].
मृण ८. ४, २२; १०. ३, २; २०. ७४, ५.
मृणत् ९. २, १४.
मृणत ३. १, २.
मृणन् ४. ३१, ३; १६. १, २.
मृणन्तम् ११. २, १८.
मृणासि ५. २९, ११; ८. ३, १८.
मृणीत ५. २१, ११; १३. १, ३.
मृणीहि ६. १४२, १; १०. १, ३१.
मृणीहि ४. ३७, १०; ५. २९, ४; ६. ८८, ३; १०. १, १७; ३, १.
मृत ८. २, ५.
मृतः ६. ४६, १.
मृतऽभ्रंजे ४. ४, १.
मृतम् ५. १९, १४; ६. १८, २.
मृतमनःऽतरा ६. १८, २.
मृतऽमनाः ६. १८, २.
मृतऽवत्साम् ८. ६, ९; १०. १, १०.
मृतस्य ९. १९, ८; १८. २, ६०.
मृताः १२. २, ४५; १८. ४, ४८; ५७.
मृतात् ६. १८, २.
मृताय ५. १९, १२.
मृते १२. २, ५.
मृतेभ्यः १८. ३, ३.
मृतैः १२. २, २२.
मृत्यवः २. २८, १; ३. ११, ५; ७; ८. २, २७; १२. ७, २.
मृत्यवे ५. ८, ५; ३०, १२; १७; ६. २८, ३; ३७, ३; ६३, २; ७६, ३; ८४, ३;

७. १०७, १; ८. १, १; ८, १०; १२. ३, ५५; ५६; ५७; ५८; ५९; ६०.

मृ॒त्युः ३. ११, ८; ४. २, २; ८, १; ५. २१, ११; २४, १३; ६. ४६, २; ९३, १; ८. १, ५; २, २३^{२}; ९. १५, २४; १०. २, १४; ७, १५; ११. ६, ११; ७, १४; ९, ३; १२. ७, १०; १०, ९; १३. ६, ४; १६. ५, २; ४; ५; ६; ७; ९; १७. १, २९; १८. २, २७; ३, ६२; १९. ९, १०.

मृ॒त्यु॒ऽदू॒ताः ८. ८, ११.

मृ॒त्युना॑ ७. ७३, १; ११. १२, १८.

मृ॒त्यु॒ऽपा॒शाः ८. ८, १६.

मृ॒त्यु॒ऽपा॒शान् ८. २, २; १७. १, ३०.

मृ॒त्यु॒ऽपा॒शैः ८. ८, १०.

मृ॒त्युऽभिः॑ ६. ६३, ३; ८४, ४.

मृ॒त्युऽभ्यः॑ १३. ८, १.

मृ॒त्युम् ४. ३५, १; २^{२}; ३; ४; ५; ६; ५. २८, ८; ६. ३२, ३; ७. ५५, १; ८. १, २१; २, ११; ८, २१; १०. १०, २६; ११. ७, १९; १२. २, २; ३; ९; २३; २९; ३०; ३, ४९; १८. ३, ४१.

मृ॒त्यून् १. ३०, ३; ११. ८, १६.

मृत्यो॒ इति॑ ८. २, ५; १०.

मृ॒त्यो॒ इति॑ ६. १३, १; २; ३; ८. २, ४; ८; १२. २, २१.

मृ॒त्योः २. १६, १; ३. ६, ५; ११, २; ५. ३०, ११; १५; ६. १३३, ३; ८. १, ४; १७; १८; १९; २, ९; २३; ७, १३; ८, १०; १८; १०. ३, ७; ८, ४४; १२. २, ३०; ४, ३७; ७, ४; १६. ८, ३२; १९. २०, १; २७, ८; २०. ९६, ७.

मृ॒थाः ३. ३१, ८; ९; ५. ३०, १७; १९. २७, ८.

मृ॒दि॒तः ११. ११, १९.

मृ॒दि॒तम् ११. १२, २६; १२. १०, १५.

मृ॒दुः ३. २५, ४.

मृ॒दुम् ५. १८, ५.

मृधः॑ १. २१, २; ३; ४. ३१, २; ५. २०, १२; ६. २, २; ७. ८९, ३; ८. ५, ८; १३. १, ५; २७; १८. २, ५९; १९. १५, १; २०. ४३, १; ७२, ३; ९१, ११.

मृ॒ध्रऽवा॑चः २०. ७३, ६.

मृ॒लया॑ति २०. २०, ६; ५७, ९.

मृ॒शन्ती॑म् ८. ९, ९.

मृ॒शा॒म॒सि॒ ३. २४, ६; ४. १३, ७.

मृषा॑ ५. १८, ९; ६. ४५, ३.

मृ॒ष्ट्वा १२. २, १७; २०.

मे॒ १. १, १; ६, २; १२, ४^{३}; १५, १; २; ३; ४; १६, २; ३०, २; ३३, ४; ३४, २; ३^{२}; २. २, ३; ५, ४; ७, ४; १५, १; २; ३; ४; ५; ६; १७, १; २; ३; ४; ५; ६; ७; १८, १; २; ३; ४; ५; ३०, ३; ३. ६, ६; ८, २; १५, ५; ६; १६, ६; १७, ७; १८, २^{२}; ५; १९, १; २०, ३; ९; १०; २२, ४; ४. १३, ६^{३}; २०, ४; २१, ५; २२, १; २५, ५; २६, २; ३; ४; ५; ६; २७, १; ३४, ८^{२}; ३५, ७^{२}; ३६, ४; ३९, २; ४; ६; ८; ५. ३, ४; ४, ६^{२}; ७; ६, ११; १२; १३; १४; ८, १; २^{२}; ९, ७; ८^{२}; १०, १; २; ३; ४; ५; ६; ७; ११, ३; ८; ९^{३}; १३, ३; ५^{२}; १५, १^{३}; २^{३}; ३^{३}; ४^{३}; ५^{३}; ६^{३}; ७^{३}; ८^{३}; ९^{३}; १०^{३}; ११^{२}; २३, १^{२}; २८, ११; ६. २, १; ४, १; ६, १; ९, १; ३; २४, २; ४५, १; ५०, ३; ५३, १; ५४, ३; ७१, २; ९४, ३^{२}; ९५, ३; १११, १; १२२, ५; १३०,

२^{२}; १३८, १; ७. १३, २; ३१, १^{२}; ३३, १; ३४, १; ३५, १; ५२, ८^{२}; ५९, १^{२}; ९४, २; १०६, १; ११४, ३^{२}; ८. २, २०; ५, ५; ६; १८^{३}; १९; ९. १, ११; १२; १३; १५; १६; १७; २, २^{२}; ७; १५; १४, १५; १५, २४; १०. १, २८; ३, १; ८^{३}; ९; ११^{२}; १२^{२}; १३; १४; १७; १८; १९; २०; २१; २२; २३; २४; २५; ४, १०; १६; १७; ५, ६; ३७^{२}; ३८^{२}; ३९^{२}; ४०^{२}; ४१^{२}; ४७; ५०; ६, १९; ३०^{२}; ९, २७; ११. १, २७; २८^{२}; ३३; १२, ४; १२. १, १०; ३३; ४४; ४५; ५३^{२}; ५९; १३. १, १२; ३२; ४३; १४. २, ९; ४२; ५०^{२}; ६३; १५. ३, २; १६. १, १२; २, ३; ३, ५; ६; ४, ७^{२}; १८. १, १२; १४; ३१; २, ३२; ३, ११^{२}; १२; ४, ४०; ५५; ८९; १९. १, १२; ४, २; ४; ७, २; ३; ४^{२}; ५^{४}; ८, २; ३^{२}; ४; ९, ५; १२^{४}; १३^{३}; १४^{२}; १४, १^{२}; १६, २; २०, २; ४^{२}; २७, १५; २८, ५^{४}; ६^{४}; ७^{४}; ८^{४}; ९^{४}; १०^{४}; २९, १^{४}; २^{४}; ३^{४}; ४^{४}; ५^{४}; ६^{४}; ७^{४}; ८^{४}; ९^{४}; ३१, १; ३; ५; ९; १०; १२; ३२, ६; ३७, १; २; ४०, १; ४३, १; २; ३; ४; ५; ६; ८; ४९, ८; ५१, १^{६}; ५५, ५; ६०, १; २; ६१, १^{२}; ६४, १; ३; २०. १२, १; १७, १; २; २७, १; ६०, २; ७२, ३; ११७, ३; १२६, ५; ७^{३}; १४^{२}.
मेक्षामि ७. १०७, १.
मेखलया ६. १३३, ३; ११. ७, ४.
मेखलाम् ६. १३३, १.
मेखले ६. १३३, २; ४; ५.
मेघाः ४. १५, ७; ८; ९.
मेडिः ११. ९, ५.
मेढ्रम् ७. १००, ३.
मेथिः १४. १, ४०.
मेथिम् ८. ५, २०.
मेदयथ ४. २१, ६.
मेदसा ४. २७, ५; १८. २, ५८.
मेदस्वता ६. ११४, ३.
मेदिनः १०. ६, २०.
मेदिना ६. ६५, ३; १२९, १; १२. १, ३३.
मेदिनीः ८. ७, ७.
मेदिनौ ६. १०४, ३.
मेदी ३. ६, २; ४. ३१, ६; ५. ३, ११; ८, ९.
मेधऽअतिथिम् ४. २९, ६.
मेधया ५. ११, ४; ६. १०८, ४; ८. ४, ६.
मेधा ९. १२, ११.
मेधाः १९. ४३, १; २०. ११९, १.
मेधान् १२. ३, १६.
मेधाम् ६. १०८, २; ३^{२}; ४; ५^{४}; १३३, ४; १०. २, १७; ११. ७, २४; १२. १, ५३; १८. ३, ११; १९. ४०, २; ३; ६४, १; २०. ११५, १.
मेधाविनः ६. १०८, ४.
मेधाविनम् ६. १०८, ४.
मेधिराय २०. ३५, ४.
मेधे ६. १०८, १.
मेध्यः १८. ४, ५१; ५२.
मेध्यम् ५. २९, १३; १८. ४, १२; १३.
मेध्यासः ४. १४, १.
मेनिः २. ११, १; ५. ६, ९; १२. ७, ५; १२; ९, १; १०, १३.
मेन्या ५. ६, १०; १०. ५, १५; १६; १७; १८; १९; २०; २१.

मेन्याः २. ११, १; ५. ६, ९.

मेर्याः ६. १३७, २.

मेषःऽईव ६. ४९, २.

मेषम् २०. ५४, ३.

मेषि १६. ४, ५.

मेष्ट १२. १, ३३.

मेष्ठाः ८. १, ५; २, १.

मेहताम् १९. ८, ५.

मेहति १३. १, ५६.

मेहनम् १. ३, ७; ११, ५.

मेहन्ती १२. ७, ११.

मैत्रावरुणम् ५. १९, १५.

मो इति १. १९, १; २०, १; २. २८, ३[२]; ५. ३, ६; ११, ७; ३०, १५; ६. १२४, ३; ७. ५५, ४; ११३, १; १२. ३, १७; १६. ४, ३; १८. ३, ९; ५२; ६२; २०. ६०, ३; ६७, २.

मोघम् ८. ४, १४; १५.

मोघम् ६. २९, १.

मोचि ३. १९, ८; ४. १६, ७; ५. ८, ४; ८. ८, १९; ११. ११, २०; १२, १९; १६. ८, ३; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३२.

मोदते ११. ६, ४.

मोदन्ते ११. ६, ५.

मोदमानौ १४. १, २२; २, ३९; ४३.

मोदाः ११. ९, २६; १०, २४.

मोदिषीष्ठाः २. २९, ६.

मोषीः ७. १०४, १; ८. २, १७.

मोहः ८. ८, ९.

मोहय ३. १, ५; ५. २१, ४; ५; ६.

मोहयतु ३. १, १; ६; २, १.

मोहयन् ३. २, ३.

मोहयन्ति ९. १३, १७.

मोहयित्वा २०. ९६, १६.

म्रियते १२. २, ३९.

म्रियन्ते ८. २, २४; १२. ४, ७; ८.

म्रियस्व ५. १३, ४.

म्रोकं २. २४, ३.

म्रोकः १६. १, ३.

म्रोकम् ५. ३१, ९; १६. १, ७.

म्लापयामसि ६. ६६, ३.

म्लापयामि ७. ९५, २.

य

यंसत् २०. ८९, ८.

यंसि २०. ३५, २.

यः १. ५, २; ८, १; १२, १; २; ३[३]; १५, २; १९, ३[३]; ४[३]; २०, २; २१, २; २५, ४; २९, २; ३०, १; ३१, ३; ३५, २; २. १, २; ३; २, १; २; ५, ३; ७, २[२]; ५; ९, ५; ११, ३; १२, २; ३; ६[२]; १४, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; २४, १; २; ३; ४; ५; ६; ७; ८; २५, ३; २७, ७; ३२, ६; ३३, ७; ३४, १[२]; ३६, ५; ६; ८; ३. ३, ६[२]; ६, ४; ११, ८; १४, २; १६, २; २१, १[२]; २[६]; ३; ४[२]; ९; २३, ५; २४, २; २७, १; २; ३; ४; ५; ६; २९, ३; ४. १, ३; ७; २, १[३] २; ३, ५; ५, १; ५[३]; ६, ४; ९, ५; १०, २; ११, ३; ५; ९; ११; १५, १०; १६, १; २[४]; ४; ६; ८[६]; १८, २; ३; ६; ७; १९, ५; २०, ४; ९[३]; २२, २; ५; २४, १; २[२]; ३; ६;

७^{२}; २८, ६; ७; ३०, ४^{३}; ३२, १; ३५,
१; ३^{३}; ५; ६; ३६, १^{२}; २^{२}; ३; १०; **५.**
१, १; २^{२}; ३; ३, ९; ११^{२}; ४, १; ५, २;
८; ६, १०^{२}; १०, १; २; ३; ४; ५; ६;
७; १२, ९; १४, २; ९; १८, ४; ५; ७;
१३; १९, ६; ९; २२, २; ३; २३, ३^{३};
२८, ११; २९, २; ६; ७; १५; ३०, ९;
१०; १२; ३१, ११; **६.** १, २; २, १;
६, १; २; ३^{२}; १४, १; १५, १; २; १६,
२; २०, ३; २६, २; २८, ३^{३}; ३०, २;
३४, २; ३; ४; ५; ३७, ३^{२}; ४२, २;
४३, २; ४६, १; ५४, ३; ६१, ३; ७३, २;
७५, १; ७६, ३; ४; ७७, २^{३}; ८२, ३; ८४,
२; ८५, १; ९२, २^{२}; १११, १; १२३, ३;
१२७, ३^{३}; १२८, ४; १२९, ३^{२}; १३३,
१^{३}; १३४, ३^{२}; १३६, ३^{२}; **७.** २, १; ५,
५; ११, १^{४}; १२, १^{२}; २७, १^{२}; ३२, १;
५१, २; ५२, ६; ५८, ४; ८; ६१, १^{२};
७३, ३; ७७, ३; ७८, ३; ८०, ३^{२}; ८२,
२; ८६, ५; ९२, १^{४}; १००, ३; ११३,
१^{२}; २; ११४, १; ४; ५^{२}; १२१, २; **८.**
३, ८; ११; १५^{३}; ४, ७; ८; १०^{२}; ११^{२};
१५; १६^{२}; ५, १२; १३; १५^{३}; ६, ५; ७;
८^{२}; ९; १६; १८; ९, २; १०, ३; ५; ७;
९; ११; १३; ११, १०; १२, २; ४; ६;
८; १३, ४; ८; १२; १६; १४, ४; ८;
१२; १६; १५, ४; **९.** १, ६; २२; २३;
२४; २, ३; ३, २; ९; ११; ४, २; ९;
११; १७; १८; ५, २२; २४; २५; २६;
२८; ३१^{२}; ३२^{२}; ३३^{२}; ३४^{२}; ३५^{२}; ३६^{२};
६, १; ६; ७, ७; १०; ११; १२; १३^{२};
८, १; २; ३; ४; ५; ६; ९, १; ३; ५;
७; ९; १०; १०, ३; ५; ७; १०; ११,

१४; १२, २६; १३, ४; ७; २२; १४, ५;
७; १५^{२}; १८; २१; १५, १०; १८; **१०.**
१, ७; ८; २८; २, ८; २८; २९; ३०;
३, ५; ५, १५^{२}; १६^{२}; १७^{२}; १८^{२}; १९^{२};
२०^{२}; २१; २५; २६; २७; २८; २९;
३०; ३१; ३२; ३३; ३४; ३५; ७, १७^{२};
२४; ३२; ३३; ३४; ३६^{२}; ४१; ८, १^{२};
५; २०; २२; २६; ३६; ३७^{२}; ९, ४; ५;
६; १०; १७^{२}; २६^{२}; १०, २^{२}; २४; २७;
११. १, ५^{२}; १५; २८; ३१; २, १३;
२३; २८; ३, २२; २३; ४, १; २; ३;
४; ५; ६; ७; ८; ९; १०; ११; १२; १३;
१४; १५; १६; १७; १८; ५, २; ५; ६,
१; १८; १९; २३; २४; ८, ४; ९; २१;
९, १२; १०, ३; ७; १८; ११, ४; १२,
२२^{३}; २६; **१२.** १, १४^{४}; २३; २४;
२५^{३}; ३०; ४६; २, १; ३; ७; १४; १५^{३};
१६; २१; ३३; ३५; ३९; ३, ६; १६^{२};
५०^{२}; ४, २; ६; ११; १२; १३; १७;
१८; २३; २८; ३८; ४४; ४६; ९, ८;
१३. १, १^{२}; २; २५^{२}; २९; ५६; ५७;
५८; ६०; २, २; १४; २६^{२}; ३, १^{३}; २;
३^{२}; ४^{३}; ५^{२}; ६^{२}; ७^{४}; ८^{२}; ९; १०; ११;
१२; १३^{२}; १४; १५^{२}; १६; १७; १८;
१९; २०; २१; २२^{२}; २३; २४^{४}; २५;
५, २; ३; ४; ५; ६; ७; ८; ६, १; ३;
१४. १, २९; ३०; ३७; ३८; २, २;
४१; ४७; ५५; ५८; ६८; **१५.** २, ३;
८; ११; १४; १७; २०; २३; २८; ३,
११; ४, ३; ६; ९; १२; १५; १८; ५,
३; १६; ६, ३; ६; ९; १२; १५; १८;
२१; २३; २६; ७, ३; ५; ८, ३; ९, ३;
१०, ९; ११; ११, ७; ९; ११; १२, ४;

७; ८; ११; १३, १४; १४, २; ४; ६; ८; १०; १२; १४; १६; १८; २०; २२; २४; १५, ३; ४; ५; ६; ७; ८; ९; १६, १; २; ३; ४; ५; ६; ७; १७, १; २; ३; ४; ५; ६; ७; १८, ३[२]; **१६.** १, ५; ७; ८; ७, ५; ८, २; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३१; **१८.** १, ६; १४; २४; ३४; ५९; २, १०; २६; ३०; ३१; ३७; ५३; ३, १३[२]; ५३; ५५; ६१; ६३; ७०; ७३; ४, २८; ५४; **१९.** ३, २[३]; ३; १५, ६; २०, २; २६, १[२]; २; ३१, २; ३२, १; ९[२]; ३५, ५; ३९, १०; ४४, २; ४६, ४; ५; ४९, ७; ९; १०; ५०, ४; ५; ५३, ८; ५६, ६; ५७, ३[२]; ५९, २; **२०.** ५, ७; ७, २; ११, ८; १२, १; १४, २; ३; ४; १६, १२; १७, ८; २०, ४; २४, १; ३०, १; ३; ४; ३१, २; ३[२]; ३४, १; २[४]; ३[३]; ४[२]; ६[४]; ७[३]; ९[२]; १०[३]; ११[२]; १३[२]; १४[२]; १५[४]; १८; ३६, १[२]; ३; ३७, १[२]; ५१, १; ३; ५३, १; ३; ५७, ७; ११; १३; ५९, ३; ४; ६२, २; ३; ४; ६३, ४; ६; ७; ६५, १; ६७, ३; ७; ६८, ४; १०; ७०, १५; ७१, ३; ७३, ६[२]; ७६, १; २; ७७, ५; ८८, १; ८९, ४; ५; ६; ७; ९; ९०, १; २; ९२, १०[२]; १६[२]; १८; ९४, १; ९५, ४; ९६, ३; ४; ११; १२; १३[३]; १४[२]; १५[२]; १६[२]; २३; १०५, ४[२]; ११७, २; १२६, २१; १३८, १; १४३, १.

यः॑ऽयः **३.** २४, २.

यकृ॑त् **९.** १२, ११; **१०.** ९, १६.

यक्नः **२.** ३३, ३; **२०.** ९६, १९.

यक्षत् **३.** ४, ६; **५.** २७, ५.

यक्ष्म् **८.** ९, ८; २५; २६; **१०.** २, ३२; ७, ३८; ८, १५; ४३; **११.** २, २४.

यक्षाणि **११.** ८, १०.

यक्षि॑ **२०.** ६७, ५.

यक्षि **५.** १२, ३; ९.

यक्ष्मः॑ **२.** १०, ५; **५.** ३०, ९; **६.** ८५, १; **८.** ७, १५; **९.** १३, ३; **१०.** ३, ५; **१२.** २, १[२]; ४, ८.

यक्ष्मः॑ऽधाम् **९.** १३, ९.

यक्ष्मऽनाशनीः॑ **३.** १२, ९; **९.** ३, २३.

यक्ष्म॑म् **२.** ३३, १; २; ३; ४; ५; ६; ७; **४.** ९, ४; १३, ५; **५.** ४, ९; ३०, ८; १६; **६.** ८५, २; ३; १२७, ३; **७.** ५५, ६; **८.** १, २१; २, १८; ७, ३; **९.** १३, ७; **१२.** २, २; १४; **१४.** २, ६९; **१९.** ३६, २; ४४, २; **२०.** ९६, १७; १८; १९; २०; २१; २२; २३.

यक्ष्माः॑ **१४.** २, १०; **१९.** ३८, १; २.

यक्ष्माणा॑म् **९.** १३, १०; ११; १२; १९; २०.

यक्ष्मा॑त् **२.** १०, ६; **८.** ७, २; ५.

यक्ष्मा॑न् **१९.** ३६, १; ४.

यक्ष्मा॑सः **९.** १३, १९; **१९.** ३६, ३.

यक्ष्मे॑ण **३.** ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११.

यच्छ॑ **१८.** २, १९.

यच्छ **१.** २०, ३; २१, २; ४; **२.** २६, २; २८, ५; **३.** २०, २; ८; **६.** ५९, १; १३७, ३; **७.** १२०, ३; **९.** ४, ६; **११.** १, ३; ११; **१२.** ३, १४; १९; ३१; **१७.** १, १२; १३; **१९.** ३१, १३; ४७, ९; **२०.** ८३, १.

यच्छत ५. ३, ७; ६. ७, ३; १८. ३, ४३.
यच्छतः ७. ५६, १.
यच्छतम् ४. २५, ६; ७. ५४, १; ८. २, ७; २०. १३, १; १३९, १; १४१, ५.
यच्छताम् ६. १२१, ३; १९. १६, २; २७, १५.
यच्छति १९. ३२, २.
यच्छतु १. १, ३; २. २६, १; ३. २०, ३; ५. ३, ८; ६. ५९, २; ७. १८, १; १०. ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; ५, ३७; ४०; १९. ९, १२[२]; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ३१, ६; ८; ६४, १.
यच्छध्वम् १४. १, ५९.
यच्छन्ति १८. ४, २९.
यच्छन्ति २०. १२०, २.
यच्छन्तु ७. ५१, १; ८. ७, २५; १०. ५, ३८; ३९; ४१; १४. २, ७३; १८. ३, ११; १९. ९, १२[२].
यच्छसि १२. १०, ११.
यच्छसे ६. ८१, १.
यच्छात् ७. ७, २; २५, १; ४२, २; ४९, १; १२. ३, ८; १९. ३१, ५; १४.
यच्छाथ १. २६, ३.
यच्छान् १२. ३, ३८; १८. ४, ४०.
यच्छामि ८. ८, १०.
यच्छेत् १२. ४, ४७.
यज ६. १२५, २; १९. ३, ४.
यजतः २. २, २.
यजता १८. १, २६.
यजति २०. ६७, १.
यजति १८. १, १८.
यजते ४. २१, ३.
यजते ९. ४, १८.
यजते इति ५. १२, ६; २७, ८.
यजत्र १८. १, २६.
यजत्राः १३. २, ४४; ४५.
यजत्राः ६. ११४, २; १९. ११, ५.
यजथाय १८. १, २९.
यजध्यै ५. १२, ७.
यजन्ताम् ५. ३, ४; ५.
यजमानः ६. १२३, १; २; १५. २, १०; ६, १४.
यजमानऽब्राह्मणम् ९. ७, १.
यजमानम् २. ३४, १; ५. ३, ९; ११. ८, १४; १९. ६३, १.
यजमानस्य ७. १०४, १; ९. ५, २; १०. ९, १; १५. २, १२; ६, १५; १९. ४२, ३; २०. १११, ३.
यजमानाः ४. १४, ५; ६. ११४, ३.
यजमानाय २. ३४, २; ४. ३०, ६; ५. २६, १२; ६. ६, १; ५४, ३; ७. १८, ४; ११५, ३; ८. ९, १४; ९. ४, १; ५, २; ११. १, ९; २, २८; १५. २, ११; १८. १, ४३; ४, ४; ५; ७; ४७; १९. ५२, १; २; २०. ५, ४; २५, ३; २७, ३; ५६, २.
यजमानासः २०. ९६, १.
यजमाने १०. ३, २३; २०. ५५, ३.
यजमानेन १८. ४, ६.
यजसि ५. १२, १.
यजस्व ६. ११०, १.
यजात् १९. ५९, ३.
यजामहे ४. ३२, २; ७. ५६, १; ८५, २; १४. १, १७; १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५;

४, १६; १७; १८; १९; २०; २१; २२; २३; २४; २०. २५, ५.
यजामि १. ३१, ३.
यजिष्ठम् २०. १०३, २.
यजीयान् ५. १२, ३; ९; १८. १, ३०.
यजुः ७. ५७, १; ९. ६, २; १०. ७, १४; २०; ११. ९, ५; १०, २३; १८. १, ३२; १९. ६, १३; ५४, ३.
यजुःऽविदः १२. १, ३८.
यजुषा ७. ७३, १; ११. ९, २४.
यजुषाम् १५. ६, ९.
यजुष्यः १०. ५, १५; १६; १७; १८; १९; २०.
यजुष्याः १०. ५, २१.
यजूंषि ५. २६, १; ११. ८, १४; १५. ३, ६; ६, ८.
यजे ३. १०, ९[२]; १०; ११; ६. १२३, ४; १९. ३७, ४.
यज्ञ ७. १०२, ५.
यज्ञऽआयुधानि १८. ४, २.
यज्ञऽआयुधैः १२. ३, २३.
यज्ञऽऋतः ८. १०, ७.
यज्ञः ४. ११, ४; ५; ३४, १; ५. २६, १२; ६. ९७, १; ७. ५, २; ७७, ३; १०२, ६; ९. ५, २१; ७, ११; १५, १४; १०. ७, १६; ८, १०; १०, २०; २७; २९; ११. १, १४; १५; १०, २०; १२. १, १; १३. १, ४८; ५५; ७, ११; १२[२]; १५. २, १०; ६, १४; ७, ४; ५; १६, ६; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; ९, ४; १७. १, १८; १८. २, १; ३, १४; ४, १३; १५; १९. १३, ९; १९, ६; २०. २७, ५.
यज्ञऽकामः ७. १०८, १.
यज्ञऽकामाः ७. २९, १.
यज्ञऽकृतः १८. ४, ७.
यज्ञऽपतिः ४. ११, ५.
यज्ञऽपतिम् २. ३५, २; ७. २७, ३; १०२, ५.
यज्ञऽपते ७. १०२, ६.
यज्ञऽपदी १०. १०, ६.
यज्ञम् १. ९, ४; १५, १; २. ३५, ५; ३. २०, ५; ४. १४, ४; १५, १६; २३, २; ५. ३, ११; ६, ८; १२, २; ७; ८; ११; २६, ६; १२; २७, ३; ८; १२; ६. ३५, २; ११४, २; १२२, ४; ७. २, १; ५, १; ४; ५; २१, १; ४; ५[२]; २८, १; २९, १; ४९, २; ५६, १; ७७, ९; ८४, १; ८७, १; १०२, १; ५; ८; ८. ३, ९; ११, ८; १०; ९. ४, ७; ५, १७; २२; १०. २, १४; १९; ५, ३१; ६, ४; १०, २५; ११. १, १०; ३४; ३६; ५, ४; ८, १४; १२. १, १३; २२; १३. १, १४; १८. १, ४२; २, ३५; ३, ४१; ४, २; ४०; ४६; १९. १, १; २[२]; ३; ६, १०; ११; १५; ५४, ४; ५८, ५; ६; २०. ६, ३; २९, २; ३२, २; ६३, १; ११०, ३; १२४, ४; १४३, ४.
यज्ञऽवचः ११. ३, १९.
यज्ञऽवर्धन १०. ६, ३४.
यज्ञऽवाहसः ६. ११४, २.
यज्ञऽवृधम् ४. २३, ३.
यज्ञऽश्रियम् २०. ६८, ७.
यज्ञऽसंशितः १०. ५, ३१.
यज्ञस्य २. ३५, ३; ५; ६. ३६, २; ४८, १;

२; ३; ६९, ३; ८. ९, १४; ९. ८, ८^{२}; १०. १०, २; ३; ११. ९, ६; १०; १३. १, १३; ६०; ३, ६; ७, १२; १५. २, १२; ६, १५; १९. ४२, २; ५८, ५; २०. ९१, २; १०१, १; १३८, ३.

यज्ञऽहोतः २०. १४२, २.

यज्ञाः ८. ९, ८; १०. १०, २४; ११. ९, ८; ११; १५; १९; १३. १, ३६; ४३; १९. १०, ७; ४२, १.

यज्ञात् १०. ५, ३१; १२. ४, ४१; १३. १, ५९; ७, ११; १८. २, २८; १९. ६, १३; १४.

यज्ञान् ३. १०, ७.

यज्ञाना॑म् ४. ३४, ५; १३. २, ३९.

यज्ञाय॑ १५. २, ११.

यज्ञायज्ञिय॑म् ८. ११, ६; १०; १५. २, १०; ३, ५; ४, ५; ६.

यज्ञायज्ञिय॑स्य १५. २, १२.

यज्ञायज्ञिया॑य १५. २, ११.

यज्ञायज्ञिये॑न ८. ११, ८.

यज्ञिय॑ः ११. १, १६; १८. १, १८; २०. ५५, १.

यज्ञिय॑म् २. ३४, १; ६. ११६, १; २०. ४०, ३; ६९, १२.

यज्ञिय॑स्य ७. ९७, १; २०. १२५, ७.

यज्ञिया॑ ६. १०८, १; ७. ८५, ४; १०. ९, ३.

यज्ञिया॑ः २. १२, २; ६. १२२, ५; ७. २९, १; ११. १, १०; १३; १७; १८; २७; १२. २, १३; २०; १४. २, १०; ६७; १८. ४, ५७; १९. ५८, ६.

यज्ञिया॑न् ११. १, ४; १८. १, १८.

यज्ञिया॑म् २०. ९४, ६.

यज्ञिया॑नाम् ४. ३०, २; ६. ५५, ३; ७. १०२, २; १८. १, ५८; १९. ४२, ४.

यज्ञिया॑सः १९. ११, ४; ५.

यज्ञियासः ११. १, १२.

यज्ञिये ७. ८५, ४.

यज्ञिये इति॑ ६. ६२, १.

यज्ञिये॑षु २०. ५९, ४.

यज्ञियै॑ः १८. १, ५९.

यज्ञे १. २०, १; ५. २६, १; २; ३; ४; ५; ७; ८; ९; १०; ११; ७. ४९, १; १०२, १; ९. ५, २; ६, ५; १०. १, ११; ३, २३; १०, १८; १२. ५, ३; २०. १३, १.

यज्ञेन॑ ७. ५, १; १२. १, ३९; ४, ३२; १३. ३, १७; १९. ६३, १.

यज्ञेभि॑ः २०. ६४, ६.

यज्ञेषु॑ १९. ५९, १; २०. १०३, ३; १०४, २.

यज्ञैः ६. १२४, १; ७. ७३, १; ८५, ४; ८. ३, ६; ५, १५; २०. २५, ५; ६७, ४; ७२, १; ८८, ६; ९२, १८.

यज्व॑नः ४. २१, ४.

यज्व॑नाम् १२. ३, ६.

यज्व॑ने ४. २१, २.

यज्व॑ऽभिः २०. ३०, ५.

यत् १. २, ३; ३, ६^{२}; १०, ३; १३, ३; १८, ३^{२}; २०, ३^{२}; २३, १; ४; २५, १; ३२, ३; ३५, १; २. १, १; २; ३, १; ७, २; ४; १२, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; ३०, ३; ४^{२}; ३२, २; ३४, २; ३५, ३; ४; ३. २, ४; ३, २; ७, २; ३; ६; १३, १; २; १४, १; २; १७, ७; २२, १; ४; २९, १; ४. १, ५; ३, ७^{२}; ७, २; ९, ९; १२, २^{२}; १३, २; ३; १६, २; ५^{२}; १९, ४; २३, ७^{२}; २६,

७; २८, १; २; ३३, ३; ४; ५; **५.** १, ४; ५; ७; २, १; ३; ३, ७; ५, ४^{३}; ६, ११; १२; १३; १४; ८, ३; ६; ११, ३; ९; १०^{२}; १३, २; १७, ७; ८; १९, ५; २२, १०; २३, ९; २५, ६^{३}; २८, ८; १२; २९, ५^{२}; १२^{२}; ३०, २^{२}; ३; ४^{२}; ५^{२}; **६.** १२, २^{४}; १८, ३; २२, २; २४, २^{२}; २७, १; २९, १^{२}; ४५, २^{२}; ३; ४९, २; ३; ५१, ३; ५३, ३; ६१, २; ३; ६३, १^{२}; ६९, १; ३; ७१, १^{२}; २; ३; ७२, ३; ७४, २; ८०, १; ३; ८३, ४; ८९, १; ९६, ३^{३}; १००, २; १०७, १; २; ३; ४; ११४, १; २; ११५, १^{२}; ११६, १; २^{२}; ११७, १; २; ११८, १; २; ११९, १; ३^{२}; १२०, १^{२}; १२१, २^{४}; १२२, ३; १२४, २; १२८, १; १३१, ३; १३३, ३; १३५, १; २; ३; **७.** ५, ३; ४^{२}; १३, ४^{२}; २१, ४; ६^{२}; २५, १^{३}; २६, २; ४२, २; ४३, २; ४५, १; ५५, १; ३; ५७, १; ५९, १^{३}; ६३, १; ६६, १; २; ६७, २^{३}; ३; ६८, १; ७०, २; ७३, १^{२}; २; ७७, ४; ८४, १; ८८, २^{२}; ९४, ३^{३}; ९५, ३^{२}; १०२, १; २; १०६, १; १११, १; ११४, ७^{३}; **८.** २, ३; १०; १२; १६; १७; १९^{४}; ३, १२^{२}; ४, १२; ५, १९; ६, २०; ७, ५^{२}; ११, २; १५, ३; **९.** १, १८^{३}; २४; २, २^{२}; १६; २५; ३, २; १३; १५^{२}; ४, ५; १४; १५; २३; ५, ३; २१; ३१; ३२; ३३; ३४; ३५; ३६; ६, ३; ४^{२}; ६; ७; ८; ९; १०; ११; १२; १३; ७, १; २; ६; ८, ७; ९; ११, १; २; ३; ५; ६^{२}; ७; ८; ९; १०; ११; १४, ४; २१; १५, १^{२}; **१०.** १, १०; ११; २, ३; २६; ३२; ३,

८^{४}; ४, २२^{२}; २५; ५, २२; ४५; ४८^{२}; ६, ३; ७, ८^{३}; ९; ३१; ८, २^{२}; ७; ११^{३}; १३; ३८; ३९; ४३; ९, १३^{२}; १५^{२}; १६^{२}; १७; १८^{४}; २२^{२}; २४; १०, ९; १०; ११; १६; २२; **११.** १, ३०; २, १०; ५, १; ६, ३; ४^{२}; ९; १०^{२}; २१; २२; ८, २३; ९, २३^{२}; १०, १; १६; २२; २३; ११, १; १३; १२, १७; **१२.** १, १२^{२}; २५; ३४^{२}; ३५; ४०; ४६; ४७; ५५; ५६; ५८^{२}; ६०; ६१; २, ५; १९; ३६^{३}; ३९; ४०^{३}; ३, ७; १३; ३०; ४३; ४८; ५२^{३}; ४, ७; ८; ९; १५; २२; ३३; ४०^{२}; १०, ४; **१३.** १, ४४^{२}; ५४^{२}; ५५; २, ३^{२}; ५; १४; २८; ३६; ४२; ४४; ४५; ३, १०^{२}; १२; १७; २२; २३; ४, ७; ११^{२}; ५, ६^{२}; ७, १५^{३}; **१४.** १, ३; ४; ६; ९; १०; १४; १५; १६; २७; ३५^{३}; ५६; २, १२; ४८; ५१; ५३; ५४; ५६; ५७; ६१^{२}; ६२^{२}; ६५^{२}; ६६^{३}; **१५.** ११, ३; ४; ५; ६; ८; १०; १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३; १७, ९; १८, २^{२}; **१६.** १, ८; ६, ४; ७, ९^{३}; १०^{४}; ११; **१८.** १, २; ४; १२^{२}; १४; २०; २२; २६^{२}; २९; ३१; ३२; ३४; ५२; २, २६; ३३; ३६; ५७; ३, ३; १९; २४; ३८; ५५; ५६; ६६; ४, ७; ४२; ४९; ५६; ६४; ८३^{२}; ८४^{२}; ८८; **१९.** ५, १; ६, ४^{३}; ५; ६; १०; १५; ९, ४; ८; १४^{३}; १३, १; १५, ४; २०, ३^{२}; २६, १; २; ४^{२}; २७, १०; ३०, १; ५; ३१, ४; ५; ३८, २^{२}; ४०, १^{२}; ३; ४४, ९^{२}; ४५, २^{३}; ३; ४७, २; ४८, ३^{३}; ४९, ७; ५०, ६^{२}; ५२, १; ४; ५; ५७, २; ४^{३};

५९, २; ३; ६४, ३; २०. ६, ९; १२, २; १५, २; १६, ७; १७, ५; ७; २१, ६; ७; २२, ६; २५, ६; २७, १; २; ४; ५; २८, १; २९, ३; ३१, ४; ३५, ११; १३; १५; ३७, २; ५; ३९, २; ४१, २; ४२, २; ४३, २^{३}; ५१, ४; ५४, २; ५६, ३; ६३, २; ६७, २^{३}; ७२, २; ३; ७४, १; ७५, १; २; ३^{२}; ७६, ४; ७७, ३; ४^{२}; ८; ७८, १; २; ८१, १; ८२, १; ८५, ३; ८७, २; ४^{२}; ६; ९२, ३; ४; ७; १४; २०; १०५, २; १०७, २; ४; ६; १११, १^{३}; २; ३; ११२, १; २; १२०, १; २; १२२, ३; १२४, ५; १२५, ५; १२६, २०; २२; १३७, १; १३८, २; ३; १३९, २^{३}; ५^{३}; १४०, १^{२}; ४^{२}; ५^{४}; १४१, २^{४}; ३^{२}; ५; १४२, ३; ४^{२}; ६^{२}; १४३, २; ५; ६; ७.

यतः १. १३, २; २. २, ३; ३. २०, १; ४. ६, ८; ३१, ५; ५. २, १; ६. ७५, २; ३; ७. २७, ६; ५८, ३^{२}; ८१, १; ८. ४, ३; ९. १, २; १०. १, १९; २८; ८, १६; २९; १४. २, १०; १९. ३, ४; १५, १; २०. १०७, ४.

यतः १८. ४, ५६.

यतन्ताम् १७. १, ३०.

यतन्ते २०. ७६, ८.

यतमः ४. ११, ५; ५. २९, २; ४; ७; ८; ९; ६. ५५, १; ८. ३, ८; १७; ९, १७; १०. २, ८.

यतमत् ५. २९, ५.

यतमस्याम् ११. २, १२; १४; २७.

यतमा १२. ३, १.

यतमाः ११. १, १३.

यतमान् ११. १, १०.

यतमानाः १२. २, २४.

यतमाने इति १८. ३, ३८.

यतमे ११. १, २६; ३२; १२. ३, ४९.

यतरत् ८. ४, १२.

यतरा १०. ७, ४३.

यतऽस्रुचा २०. २५, ३.

यतस्व २. ६, ४.

यति १०. ३, ६; १२. २, २४.

यतिऽधा ८. ९, ७; १०. १, २०.

यतिऽभ्यः २०. ९, ३; ४९, ६.

यत्ऽईव ९. १५, १५.

यती ६. ६०, २.

यतीः २. ५, ३; ३. १३, २; ५. २१, ९; ६. ८५, ३.

यतीः १४. १, ३२; २, ५२.

यतेते इति ७. ५९, २.

यत्ऽकामः ६. १२२, ५; १०. ९, २७; ११. १, २७.

यत्ऽकामाः ७. ८४, ४; ८५, ३.

यत्ऽयत् ११. ७, १५; १२. १, ४६; ३, ३; १३; २२; ३९; २०. ११८, २.

यत्र १. ४, ३; ८, ४; २५, १; २. १, १; ५; २५, ५; ३. १३, ७; २८, १^{३}; ५; ६^{२}; २९, ३; ४. ११, ८; १९, २; ३७, ४; ५^{२}; ५. १७, ४; १८; १९, ६; ८; ६. २२, २; ९८, ३; १२०, ३; १२४, २; १४२, २; ७. ५, १; १९, २; ८. २, २५; ३, ५; ९. ५, ५; ९; १४, २; ३; २२; १०. ७, ४; ५^{२}; ६; १०^{२}; ११^{२}; १४; १५; १६; २२^{२}; २४; २६; ८, १६; ३३; ३४^{२}; ३९; ९, ५; १०, १२; १७; १२. ७, १२; १३. ३, १८; १४. २,

३६; **१८.** १, ११; ५०; २, ५५^{२}; ५७; ३, ९; ४, ३; १०; १५; **१९.** ३९, ८^{२}; ४३, १; २; ३; ४; ५; ६; ७; ८; **२०.** २२, ५; २५, ६; ९२, २; ९४, ७; १०७, १५; १२६, १.

यत्रऽकामम् **९.** ३, २४.

यत्रऽयत्र **१०.** १, २९; **१९.** ३, १.

यथा **१.** २, ४; ३, ९; ११, ६^{३}; १६, ४; २२, २; २९, ३; ५; ६; ३४, ५^{२}; **२.** ३, १; १५, १; २; ३; ४; ५; ६; २८, ४; ५; ३०, १^{३}; ३; ५; ३१, ३; ३६, ४; **३.** २, ६; ५, ५; ६, ३; ६; ८, २; ९, १; ११, ३; १५, २; १७, ८^{२}; २०, ६; २५, ५; **४.** १, ७; ४, ३; ५, ५; ८, ६; १३, ४; २३, २^{२}; ३९, १; ३; ५; ७; **५.** ८, ७; ८; १४, ४; २१, ४; ५; ६^{२}; २५, २; २९, १; २; ३; **६.** ८, १^{३}; २^{३}; ३^{३}; ९, २; १४, २; १५, ३; १७, १; २; ३; ४; १८, २^{२}; २१, २; २९, ३; ३३, २; ४२, १; ३; ४३, ३; ४६, ३^{३}; ५८, २^{२}; ६४, १; ३; ६९, २; ७०, १^{४}; २^{२}; ३^{४}; ७२, १; २; ७४, ३; ८१, ३; ८५, ३; ९७, १; १०२, १; २; १०५, १; २; ३; १११, २; ४; १३०, ३; १३८, ५; १३९, ४; ५; १४१, ३^{२}; **७.** १४, १; ३८, १; ३९, २; ५२, १; ५; ९५, ३; ९९, १; ११८, १; २; **८.** २, १३; ४, २१; ५, १९; २१; ७, ७; १९; २२; ८, १; ६; १४; १५; **९.** १, ११; १२; १३; १६; १७; १९; २, १८^{२}; **१०.** १, ५; १३; ३२; ३, १३; १४; १५; १७^{२}; १८; १९^{२}; २०^{२}; २१^{२}; २२^{२}; २३^{२}; २४^{२}; २५^{२}; ६, ३३; **११.** ६, १९; ११, २३; **१२.** २, २५^{३}; ३, ५४; ४, १४; १५; ३४; ११, ३; **१४.** १, १८; २०; ४३; ५०; २, ७५; **१५.** ११, २^{३}; ६; ८; १०; **१६.** ६, ११; **१७.** १, २०; २१; **१८.** १, १८; ६१; २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५; ५०; ३, २१; ५०; ६७; ७०; ४, ५५; **१९.** २, ५; ४, ५५; २४, २; ३; २६, ३; ३१, ९; ४६, ७; ४९, १०^{२}; ५०, ४; ६; ५७, १^{३}; **२०.** १७, १; २२, ३; ४; २५, १; २; २७, १; ३०, २; ३२, २; ५१, १; ७०, २; ७३, ५; ७९, १; ९२, १; ९४, ४; ९५, १; ९६, ८; १२५, १; २.

यथा **६.** १४, ३; **१३.** २, १७; १८; **२०.** ४७, १४; १५; ८५, २.

यथाऽअङ्गम् **६.** १०१, १.

यथाऽइव **२०.** १२६, ७.

यथाऽओकसम् **१२.** १, ४५.

यथाऽनाम **४.** ३८, ७.

यथाऽपरु **९.** ५, ४; **१८.** ४, ५२.

यथाऽबलम् **३.** २०, ९.

यथाऽभागम् **७.** ११४, २.

यथाऽयथम् **१०.** ८, २३; ९, ४.

यथाऽलोकम् **११.** ११, २६.

यथाऽवशम् **३.** १३, ४; **७.** १०९, १; **१८.** ३, ५९.

यथाऽस्थाम **७.** ६९, १.

यदा **३.** १३, ६; **६.** १११, १; ३; **८.** ७, २१; **९.** १५, १५; **११.** ६, ५; १४; १६; १७; १०, ११; १८; **१२.** ३, २; ४, २९; ३०; **१४.** २, २०; **१८.** २, ४; ५; **२०.** १६, ६; ७३, ४; ८७, ५; ९१, १०; ११४, २; १२३, १.

यदि **१.** १६, ४^{३}; २५, २^{३}; ३^{३}; **२.** १४,

५^{३}; ३. ११, १; २^{३}; ४. ९, १०^{२}; १२, ७^{२}; २७, ६^{२}; ५. २, ४; ८, ६; १४, ६^{२}; ७^{२}; १६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ६. १११, २; ११३, १; ३; ११५, २^{२}; ११६, ३^{२}; ११९, २; १२४, २^{२}; ७. ३९, ५^{२}; ६८, १^{४}; ७५, १^{२}; ८. ४, १४; १५^{२}; ९. १३, ८; १०. १, २४; ३०; ३, ६; ११. १२, १७; १२. २, ४^{२}; ३, ३०; ४, ५३^{२}; १३. २, ६; ७; ७, १७; १४. २, ५९; ६०; १८. १, २१; ३२; २, ७; ३५; २०. २६, २; ३६, ४; ५३, ३; ५७, १३; ९६, ६; ७^{३}; १०७, ७.

यदो इति १८. २, ५.

यद्दौ २०. १४१, ४.

यन् १८. १, २९.

यन्तः ४. १४, ४; ५. ७, ४; २०. १००, १.

यन्तम् ६. १२२, ४; १८. २, ९.

यन्तवे २०. ६१, ६; ६२, १०.

यन्ता २०. ७२, २; ७५, १.

यन्ता ६. ८१, १.

यन्ति १. १७, १; २. २, ३; ४. ३, १; ३३, ५; ५. २१, ८; ६. ७, १; ९८, ३; ७. ४१, १; ८. ६, १४; १०, ५; ९; ११; १३; १०. २, ६; ७, ५; ९, ४; १२. २, २५; ३, २५; १३. १, ३५; ३, १७; १४. १, ३४; २, १०; १८. ४, २; ३; ७; २०. १८, ३.

यन्ति १. ४, १; २. १, ३; ४. २१, ४; ३४, २; ५. ४, २; ८. २, २४; ८, १२; ९, ६^{२}; ९. ५, २९; १०. ७, ५; १२. ३, २६; ४, ५२; १३. १, १३; २, १७; १५. १७, ८; १८. ३, १७; २०. ६, ४; २५, २; ४७, १४; ६९, ३.

यन्तु ८. ४, ५.

यन्तु १. ७, ५; २. २४, १; २; ३; ४; ५; ६; ७; ८; २६, १; ३५, ५; ३. ४, ३; ११, ५; ७; १७, ५; १९, ६; ४. १४, ५; १५, १; ८; ३१, १; ३४, ५; ६; ७; ३७, ३; ५. ३, २; ८, १; ११, ९; २०, ३; ७; ६. ३२, ३; ७. ११९, २; ८. ३, १४; ५, ९; ७, ७; १०; ८, १३^{२}; २१; ९. २, ४; ७; ५, १५; १०. ३, ९; ११. २, ११; ११, ११; १९; १२. ३, २०; ४९; १३. १, ३२; १९. १३, ९; ५८, ५.

यम् १. २६, १; २. ११, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; २३, १; २; ३; ४; ५; ३. ५, ३; १५, ४; १६, २^{२}; २१, ३; ४^{२}; ५; २७, १; २; ३; ४; ५; ६; ४. २, ३; २३, १; २४, ५; ३०, ३; ३५, १; २^{२}; ४; ३६, ७; ८; ५. ७, २; ५; ८, ५; ६. २, २; २६, ३^{२}; ६५, २; ८१, ३; १०९, २; ११८, ३; १२३, १; १३२, १; २; ३; ४; ५; ७. ३२, १; ८६, ५; ६^{२}; ८. १, ११; ५, ११; ९. ५, १९^{२}; १०. ५, १५; १६; १७; १८; १९; २०; २१; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४२; ६, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २२; २३; २४; २५; २६; २७; २८; ३२; ७, २३; ९, २६; ११. १, ७; ८, ७; १२, १२; १३; १२. १, २३^{३}; २४; २, ३; ३७; ३, ४^{२}; ५^{२}; १२; १३. १, २१; ५१^{२}; २, ४^{२}; ६; ७; ३६; १४. १, ३; १३; ३७; २, २२; ४२; १६. १, ५; ६, ४; ७, ५; १८. २,

३०; ३, ६; ५४; ४, ४२[२]; १९. २०, १; २७, ९; ३२, ९; ३५, १; २; ३८, १; ३९, ९[४]; २०. ९, ४; २६, ३; ३०, २; ३३, १; ३४, ५; ८; ९; ४९, ७; ५५, ३; ६७, ७; ७३, ४; ७६, ८; ८९, ८; ११७, १; १२६, ४; १५.

यमं १८. १, ५९.

यम १. १४, २; १८. १, १५; ६०; २, १२; १५; १८.

यमः ४. ३४, ४; ५. २४, १४; ६. ४६, १; ६३, २; ८४, ३; ९३, १; ८. १३, ६; ९. १२, १; २०; १२. ३, ८; १५. १४, १३; १६. ४, ४; १८. १, ४७; ५०; ५५; २, ३२; ३७; ३, ४१; ४६; ५२; ६३; ६९; ४, २६; ४३; ५४; १९. २०, १.

यमः ४. ३, ७[२].

यमत् ६. ३५, ३; ५६, १; १०. ४, ८; २०. ५३, २; ५७, १२.

यमते २०. ७८, २.

यमंऽदूताः ८. ८, ११.

यमऽदूतान् ८. २, ११.

यमन् ७. १२२, १; २०. १४३, ५.

यमंम् २०. ६६, १.

यमम् ४. ४०, २; ९. १५, २८; १४. २, ६९; १८. १, ४९; ५४; २, १; ३, १३; ६२.

यमय ६. १३७, ३.

यमराजऽसु १८. २, २५.

यमऽराज्ञः १२. २, ८; १८. २, ४६.

यमऽराज्यें १२. ३, १; ४, ३६.

यमऽराज्येंषु १२. ३, ३.

यमऽश्रैष्ठान् ११. ८, ११.

यमऽसदनात् १२. ११, ३.

यमस्यं २. १२, ७; ३. २९, १; ५. ५, ८; ३०, ६; ६. २९, ३; ४६, २; ९६, २; ११०, २; ११७, १; ११८, २; ७. ५५, १; ११७, २; ८. १, ९; ७, २८; ९, २३; १०. ५, १२; १२. २, ५४; १६. ५, १; ४; ५; ६; ७; ८; १८. १, ८; १०; ३४; ५३; २, १३; २७; ५६; ३, ६६; ७०; ४, ३१; ३२; १९. ५६, १; ५७, ३; २०. २५, ५.

यमाः ९. १४, १६; १०. ८, ५.

यमार्य ५. ३०, १२; ६. २८, ३; ६३, २; ८४, ३; १३३, ३; १२. ३, ५६; १८. २, १[२]; २; ३; ४, ५५; ७४.

यमि १८. १, १३; १६.

यमिनि ३. २८, ४.

यमिनीं ३. २८, १; ५; ६.

यमीः १८. १, १०.

यमे ३. १०, १; ४. ३४, ३; १८. २, ६; ३२.

यमे इवेति यमेऽइंव १८. ३, ३८.

यमेत् १८. २, ३.

यमेनं ६. ३२, २; ६३, ३; ८४, ४; १८. २, ११; २१; ३, ५८.

यम्यमि १८. १, ८.

ययस्तु ८. ४, २.

ययां ३. १८, १[२]; १०. ८, १०; १०, ४[३]; ११. ४, ५; १८; १२, १५; १४. २, ९; १७. १, १३; १९. ९, ३; २०. ३६, १०.

ययार्थ १८. १, ४३; ४, ४७.

ययाम ९. ३, ३.

ययुः ४. २४, २; १८. १, ६१; २, १६.

ययोः ४. २५, २[२]; २६, ५; २८, १; २; ५; २९, ७; ६. १३८, ४; ७. २६, १.

य॒व ६. १४२, १.
यव॑ऽआशिरम् २०. २४, ७; ९५, १.
यव॑ः ८. ७, २०; ९. १, २२; २, १३^{३}; ११. ८, १५.
य॒वन् ३. १७, २.
यव॑म् ६. ३०, १; ९१, १; १४०, २; १४२, २; २०. १७, ७; १२५, २.
यव॑म्ऽइव २०. १६, ३.
यव॑ऽमत् २०. ७, ३; ८९, ७.
यव॑ऽमन्तः २०. १२५, २.
यव॒र्य॑ ६. ४, ३; २०. ८३, १.
य॒व॒य १. २, ३; २०, ३^{२}; २१, ४; ४. १९, ७; ५. २२, ६; १२. १, ३२; ५०; २०. ६९, ८.
य॒व॒यत् ६. ४, २.
य॒व॒यत॑म् १. २०, २.
य॒व॒यन्तु ९. २, १३.
य॒व॒याः ७. ६७, १.
य॒व॒ऽयावा॑नः ९. २, १३.
यव॑साऽइव १८. १, २२.
यव॑स्य २. ८, ३; २०. २१, २.
यवाः ९. ६, १४.
यवा॑न् ६. ५०, १; २.
य॒विष्ठ ५. २९, ४; ८. ३, ८.
यवि॑ष्ठाः १८. ४, ६१.
य॒विष्ठ्य १९. ६४, ३.
यवे॑ ११. ६, १३.
यवे॑न ७. ५२, ७; २०. १७, १०; ८९, १०; ९४, १०.
य॒व्याभि॑ः २०. १००, २.
यश॑ः ३. २२, १; ६. ३९, १; ६९, १; ३; ८. ४, ११; ९. ८, ५; १०. ३, १८; १९; २०; २१^{२}; २२^{२}; २३; २४; ८, ९; ११. ७, २५; १०, २०; १२. ६, २; १३. ५, १; ६, १; १४. २, ५६; १५. २, ८^{२}; १४^{१}; २०^{२}; २८^{२}; १९. ३७, १; ५८, ३; २०. ६, ६.
य॒शः॒ऽत॑मः ६. ३९, ३; ५८, ३.
यशः॑ऽभिः ६. ३९, २.
य॒शस॑ः २. ६, २; ६. ३९, २; ५८, २.
य॒शस॑म् ६. ३९, २; ५८, १^{३}; १९. ५८, ३; २०. ११८, १.
यश॑सा १०. २, ३३; ३, १७; १८; १९; २०; २१; २२; २३; २४; २५; ६, २७; १२. ५, २; १३. ८, ४; ५; ६; ९, १; २; ५; १९. ५६, ६.
य॒शसे॑ ३. २१, ५.
य॒शस्य॑व॑ः ४. ११, ६.
यश॑स्वतः २०. ७१, १२.
यश॑स्वती १८. १, २०.
यश॑स्वतीः ६. ५८, २.
यश॑स्वान् ६. ५८, २.
य॒श॒स्विन॑ः १९. ५६, ६.
य॒श॒स्विन॑म् ६. ३९, २.
य॒शाः ६. ३९, ३^{४}; ५८, ३^{४}; १३. १, ३८^{३}.
यस्मा॑त् ४. ३५, ४^{२}; ६; ६. ७१, २; ९. ३, २०; १०. ७, २०^{२}; ३१; ११. ३, ३; १२. ३, ४५; १३. ३, २^{२}; १६. ६, २; १९. ७२, १; २०. ३४, ९.
यस्मि॑न् ४. २४, ५^{२}; ३५, ६; ५. २, ६; १७, १२; १३; १४; १५; १६; १७; ८. ९, ३^{२}; ९. ७, १३; १४, ११; १४; २१; १५, १८; १०. ७, ७; १२^{२}; १४; ८, १९; ३७; ३८; ११. २, ११; ३, २०; ६, १; १८; १२. २, १७^{२}; ४, १४; २४; १३. ३, १; ५; ६; १०; १४. २,

८; १८. १, ३५; ३६; २०. ४४, २; ६९, ७; ८९, ६; ९२, १९; १०७, ९; ११०, २.

यस्मै॑ ४. २४, ३; ४[२]; ३५, ५; ५. ३०, १७; ६. ११८, ३; ८. १५, १; १०. ६, ३४; ७, ३९[२]; ८, २६; १९. ३२, २; ८; ३९, २; ३; ४; ४८, १; २०. १२६, ३.

यस्यं १. ५, ३; २०, ४; २. १३, ५; २४, १; २; ३; ४; ५; ६; ७; ८; ४. २, १[२]; २[२]; ३; ४[३]; ५[३]; ९, ४; ११, ५; २३, ७; २४, ३; ४; ५; ६; ३५, ५; ६. ५, ३; ३३, १; ७६, २; ११८, ३; १३३, १; ७. १५, २; २६, २; २७, ३; ४१, १[३]; ८१, १; ९. ६, १[२]; २; ७, ८; ९; १३, ३; ६; १०. ६, ३१; ७, १३; १५; १६; १८[२]; १९[२]; २०; २३; २७; ३२; ३३; ३४; ८, १; ११. २, २२; ३, २१; ६, १; १३. १, ३७; ३, १६; २४[२]; १५. १०, १; ११, १; १२, १; १३, १; ३; ५; ७; ९; ११; १९. ४, ४; ५६, ५; २०. १, २; १५, १; ३; १७, ६; ३१, ४; ३४, १; ७[४]; १५[३]; ३६, ५; ४३, ३; ४५, २; ६१, ५; ६२, ९; ६५, ३; ६९, २; ७६, १; ९२, ९; १७; १०५, ५; १११, ३; १२६, १२; १६[२]; १७[२].

यस्याः ६. ६२, २; ८४, १; ७. ७, २; २८, १; ८. ९, ८; ९. ३, १०; १०. २, २८; ३०; ११. १२, २७; १२. १, २; ४; ८; ४२; ४३[२]; १९. ४७, २; २०. १२६, २३.

यस्या॑म् १२. १, ३[३]; ४; ५[२]; ९; १०; १३[३]; २७; ३७; ३८[४]; ३९; ४१[३]; ४२; ५१; ५२; ३, ९; १४. २, ३८[२]; १८. २, ४८.

य॒ह्व ५. १२, ३.

य॒ह्वः १८. १, १८.

य॒ह्वाःऽइ॑व १३. २, ४६.

या १. १५, २; १६, ३; १८, १; २०, १; २८, ३[३]; २. ३, २; ९, १; २६, ३; ३१, १; ३५, १; ३. २, ६; १०, २; ४; १८, ४; २४, ६; २५, १; ३; ४. १७, ३[३]; ३८, ३; ५. ३, ६; ७, ९; ६. ४, ३; २२, ३; ३८, १[३]; २[४]; ३; ४; ४४, २; ७३, २; ७. ४३, १; ४८, १; २; ३; १२०, २; ८. ३, १२; ४, १७; ९, ११; १४; ९. १, ८; ३, २१[२]; ५, २७; १४, १९; १०. ५, ४८; ८, १०[४]; ९, १९; २१; १०, २८; ११. ६, ९; ९, २५; १०, ४; ७; १७; २६; ३०; ११, २; १२. १, २; ४; ८; ३७; ३, ५४; ४, ४४; ४६; ४८; १४. २, ७; १९; २२; ३८; ४८; ५०; ७४; १७. १, १३[४]; १८. १, ४३; २, ३१; ४, ४७; १९. ३, ३[२]; ४, १[२]; ९, ३; ४०, ४; ५५; २; २०. २०, २; २५, ३; ५७, ५; ८७, ५; ८८, ३; ९५, ४.

याः १. ४, २; ६, ४; १७, १; २२, ३[२]; २९, २; ३३, १; २; ३[२]; ४; २. २, ४; ५; १०, ४; ३. २४, ३; ४. ५, ३[२]; ८, ५; २१, ५; ३२, २; ३८, ४; ५[२]; ५. १, ८; १३, ९; १८, १२; १९, ११; २१, ९; ६. २१, १; २४, ३; २५, १; २; ३; ९०, २; ९६, १; ९९, २; ७. ३६, २; ५०, २; ५१, १[२]; ८०, २[३]; ११६, १[२]; १२०, ४; ८. २, २७; ५, ९[४]; ७, १[२]; ४; ८; १०[२]; ११; १७; १८[३]; २३; २४[५]; ९. २, २५; ४, ६[२]; ५, १९; ६, ५; १३, १३; १४; १५; १६; १७; १८; १०. ९, १६; २०[३]; २३[२]; ११. २, ३; ६, १७; ८, ९;

२२; १०, २१; २७; २८; ३०[२]; ११, १; १२. १, १२; ३१[४]; ५६; ३, ४१; ४, ५; ४१; ४३; १३. १, २; ९[२]; १०; ३, १; १४. १, ४५[३]; २, ७[२]; २९[२]; ४९[२]; १७. १, २८; १८. २, ८; ९; २०; ३, ६९; ४, २६; ४३; १९. २, ३; ८, ६; १२, ११; ३४, २; ७; २०. ३६, ११; ५५, २; १०४, १; १०९, १; १३९, १.

याचति ९. ६, ४; १०, ८.

याचत्ऽभ्यः १२. ४, १; २; १२.

याचन्ति १२. ४, २६.

याचमानः ६. ११८, ३; ११९, ३.

याचमानस्य ७. ५९, १.

याचयते १२. ४, ३८.

याचामि ५. ७, ५.

याचामि १. ५, ४; १५. १३, १३.

याचितः १२. ४, ४८; ५०.

याचिताम् १२. ४, १३; १९; २५; ३६.

याचितुम् १२. ४, ३१.

याचेयुः १२. ४, २२; ४८.

याच्ञ्याय १२. ४, ३०.

यात् १२. १, ५७; २०. १६, १०.

यात १. १५, २; ६. ७३, ३; १८. ३, १४[२]; ४, ६२; ६३[२]; २०. १४३, ९.

यातः ७. ८६, १; १३. २, ११; १४. १, २३;

यातम् ३. ८, ६; ६. ९४, २; १०. ८, ८; २०. १२५, ३; १४१, १.

यातम् ५. २६, १२; ११. २, १; २०. १४१, १; ४; १४३, ४; ५.

यातयन्ताम् ५. २९, ६; ७; ८; ९.

यातवः २. २४, १; २; ३; ४; ५; ६; ७; ८; १०. ७, १८; १३. ६, ६.

यातवे १२. १, ४७; १३. २, ८; २०. ६३, ९.

याता २०. ९२, १६; १०५, ४.

याताम् १८. १, ३३.

याति १. ३३, २; ३. २१, ३; १३. १, २३.

याति ३. ३१, ५; ४. ३४, ३; ६. ६०, १; १०. ८, १८; १३. २, २४; ३८; ३, १३; १४; २०. ४७, २१; ८७, १; १४२, ३.

यातु ३. ८, १; ६. ३५, १; ४०, २; ७३, १[२]; ७. ६०, १; १८. २, १०; २०. ७७, १; ९४, १.

यातुऽचातनम् १. १६, २.

यातुऽजम्भनम् ४. ९, ३.

यातुऽधान ८. ४, १५; १६.

यातुऽधानः ४. २८, ६; ८. ३, ८; ११; १४; १५; १७; ४, १५.

यातुधानऽक्षयणम् ६. ३२, १.

यातुऽधानम् १. ७, १; ४. ३, ४; २०, ८; ८. ३, ५; ४, २४.

यातुऽधानस्य १. ८, ३; ८. ३, ४; १०.

यातुऽधानाः १. ७, ३; ७. ७३, २; ८. ३, ९; १६; १९. ४६, २.

यातुऽधानाः ६. ३२, २.

यातुऽधानान् १. ७, २; ५; ६; ७; ८, १; २८, १; २; ४. १८, ८; २०, ६; ५. १४, २; २९, ११; ८. ३, २; ३; ६; ७; १२; १३; १८; २१; १०. ५, ४८; ४९.

यातुऽधानीः १. २८, ४; ४. १८, ७.

यातुऽधानेभ्यः ६. १३, ३.

यातुऽधान्यः १. २८, २; ४; २. १४, ३; ४. ९, ९; २०, ६; १९. ३६, २; ३९, १; ५; ६; ७; ८; ४७, ७.

यातुमत्ऽभ्यः ८. ४, २०; २५.

यातुऽमान् १. ७, ४.

यातुऽमावत् ८. ४, २३.

यातुऽहा १. १६, १.
यातून् ४. ९, ९.
यातूनाम् ५. २९, ८; ९; ८. ४, २१.
यात्याः १४. १, १२.
याथः २०. १४१, २.
याद्मम् २०. ३७, ८.
यान् २. ३५, १; २; ३. ६, १; ३; ५; ११, ५; ७; २३, ३; ५. ८, ७^{२}; ७. १०२, ३; ८. ८, १६; १२. २, ३८; ५०; ५२; १७. १, ७^{२}; १८. १, ४७; ३, ६८; ४, २९.
यानान् ५. १२, २.
यानि २. ५, ५; ६, १; ३. २, २; २३, ४; ४. ७, ७; ५. ३, ४; ६, २; १९, १३; ८. ९, ३; ९. ३, ६; ६, १५; १०. ७, ४०; ९; २; २४; ११. २, ५; १४. २, ७; १९. ८, १^{३}; ९, ५; १३; २०, २^{२}; ३१, ४; ३७, १; ४८, १^{२}; ४९, ३; ६४, ३.
यन्ति १९. ४३, १; २; ३; ४; ५; ६; ७; ८.
याभिः १. ४, २; ४. २१, ३; ५. ४, ५; ७. ५०, २; ९. २, २५; १३. १, ९; १४. १, ३७; १८. २, ९; २०. १२२, १.
याभ्याम् २. ३२, ६; ४. २५, २; २६, ६; ७. ५६, १; ११५, २; १०. २, ३; ८, २०; ११. ४, २; ३; १३; १४; १५; १६; १७; ११, ४; १९. १३, १.
याम् १. १३, ४; ३. १०, २; ३; ४. ४, १; १७, ४^{३}; १८, ५^{३}; १९, ६; ५. १७, ४; १८, ९; १९, १२; ३१, १^{३}; २^{३}; ३^{२}; ४^{२}; ५^{२}; ६^{३}; ७^{३}; ८^{२}; ९^{२}; ६. ७८, १; ९०, १; १०८, ३^{४}; १३३, ५; १३७, १; ७. १६, १; ८. २, १६; ४, ६; ९, ८; ९. १, ९; २, ५; १०. १, १; ४^{३}; १८^{२}; ११. १, २४; १०, ७; १२, ९; २७; १२. १, ७; ८; १०^{२}; ५१; ६०; ४, १९; ४९; १४. २, ६५; १८. २, ३०; १९. ४, १; २; २०. ११७, ३.
यामन् २०. ६७, ४.
यामनि १८. ३, ६७; २०. ७९, १.
यामन्ऽयामन् ४. २३, ३.
यामम् १०. २, ६.
यामम् ६. ११६, १.
यामि २०. ११८, २.
यामि ४. ३७, ७; ८. ३, १; १३. २, ३७; १९. ३, ४; २०. ९, ३; ४९, ६.
यामुनम् ४. ९, १०.
यामेषु ६. २१, २.
यावत् ३. १९, ३; २२, ४; ५^{२}; ४. ६, २; ५. १९, ४; २२, ५; ६. ७२, २; ३; ७५, ३; ८. ९, ६; ९. २, २०^{२}; ९, २; ४; ६; ८; १०. १०, ३४; ११. ३, २५; १२. १, ३३; ४, २७.
यावतः १३. २, ४२; २०. ८२, १.
यावत्ऽअङ्गीनम् ६. ७२, ३.
यावती इति ४. ६, २; ९. २, २०.
यावतीः ८. ७, १३; ९. २, २१^{२}; २२^{२}; १४. २, ४९; ५१.
यावतीनाम् ८. ७, २५^{२}.
यावतीषु ८. ७, २६.
यावत्ऽश्रेष्ठाभिः ७. ३२, १.
यावत्ऽसबन्धु १८. ४, ३७.
यावन्तः ६. ११६, ३; ७. १४, २; १२. ३, ३६; ४०; ५०; १४. २, ४९; १९. ५८, ६.
यावन्तौ १२. ३, १.
यावान् ४. ११, ८.

यासत् २०. १२, ७.
यासाम् १. ३३, २; ३; ३. २३, ६; ४. ३८, ५; ६. ९, ३; ८. ७, २; १६; १२. ३, ३१.
यासि १३. २, ३; २०. १४२, ३.
यासि १३. १, २१; ३८; १९. ५६, १.
यासु १. ३३, १^{२}; ४. २, ६; ८. ७, १८.
यास्यन् १३. २, २८.
याहि ७. १२२, १; २०. १२, ४.
याहि २. ५, १; ३४, ५; ५. ८, २; ११, ८; १२, ३; २०, १२; २६, १२; ६. ९२, १; ७. ७५, २; ७७, ९; १०२, १; ८. ३, ३; १०. १, १५; १२. ३, १९; ५३; १३. २, ५; १८. १, ९; ३, ४७; ४८; ४, २; ३; ८; १९. ५६, ६; २०. ३, १; ४, १; १३, ४; २३, १; ८; ३६, ११; ३८, १; ४७, ७; ८४, १; २; ३; ८६, १; ९४, २; ५; १०३, २.
युक्तः ५. १७, १५; २९, १; ९. १२, २४; १३. ३, १९.
युक्तऽग्रावा ९. ७, १०.
युक्तऽग्रावाणः २०. ३४, ६.
युक्तम् ८. ९, ७; १८. १, १५.
युक्ता ९. १४, ९.
युक्ताः ५. २६, ४; ५; ९. १४, १४; १९; १०. ५, ६; ८, ८; १८. ४, १.
युक्त्वा ६. ३७, १; २०. १२, ७.
युक्ष्व १८. १, २५; २०. ५६, ३.
युगस्य १४. १, ४०; ४१.
युगा ३. १७, १; २.
युगानि १८. १, ११; २०. १०७, १५.
युगे इति ८. २, २१.
युगेऽयुगे २०. ६७, २.
युङ्क्ते १८. १, ६.
युङ्ग्धि ८. ३, ११; ११. १, ९.
युजः ६. ३३, १; ११. १०, २५.
युजम् २०. ७०, ११; ८९, ४.
युजा ४. २३, ५; ३१, ४; ३२, १; ३; ५. २१, ११; ७. ५२, ४; १३. १, ३; २०. ३, ३; १८, ६; ३८, ३; ४७, ९; ७०, २०; १३७, ९.
युजे ६. ५४, १; २; १८. ३, ३९; २०. १२, ३.
युज्यः ५. ११, ९; १०; ६. ५१, १; ७. २७, ६; २०. ११७, २.
युज्यताम् १४. १, ६४.
युज्यताम् २. १२, २.
युज्यते ८. ९, ३; १०. ८, १०^{२}.
युज्यते १०. २, ३.
युज्यन्ते १२. १, ३८.
युज्यमानः ६. ९२, १; ९. १२, २४; १८. १, ३९.
युज्या २०. १०४, ४.
युज्याय २०. ३७, ९.
युञ्जन्ति २०. २६, ४; ५; ४७, १०; ११; ६९, ९; १०; १००, ३.
युञ्जन्ति ३. १७, १; ९. १४, २; १३. ३, १८.
युञ्जन्तु ३. ३, १; ६. ९२, १.
युतऽद्वेषसः २०. २१, ४.
युताः १३. ४, ६.
युताम् ११. १२, १६.
युत्ऽसु १९. १३, ७.
युद्धाय ४. ३१, ४.
युधः १०. १०, २४; १९. १३, ३; ४.
युधम् ६. ६६, १; १०३, ३; २०. २१, ७.

युधा १. २४, १; १०. ६, १६; २०. ११, ७; २१, ७; ४६, १; ८७, ३; ११४, १.
युधाम् ७. ८६, ३.
युधि २०. ७०, १९.
युधे ४. २४, ७; २०. ३५, १३.
युधेन्यानि ५. २, ५; २०. १०७, ८.
युध्यत २०. १३७, ८.
युध्यन्ते १८. २, १७.
युध्यन्तें १२. १, ४१.
युध्यमानाः २०. ३४, ९.
युनक्त ३. १७, २.
युनक्ति ३. ३१, ५.
युनक्तु ५. २६, २.
युनक्तु ५. २६, १; ३; ७; ८; ९[२]; १०; ११.
युनक्षि १९. ५६, १.
युनज्मि ४. २२, ५; ७. ८३, २; १९. २५, १.
युनज्मि ३. ३०, ६; १०. ५, १; २; ३; ४; ५; १८. २, ५६; २०. ३७, ६; ८६, १.
युपितम् ४. २५, २.
युयुक्षे ८. ९, ७.
युयुतम् २०. १३९, १.
युयुत्सति ११. १२, २६.
युयोजं ६. १३३, १.
युयोतु ७. ९७, १; २०. १२५, ७.
युयोपिम ६. ५१, ३.
युयोम ७. ७१, १.
युवतयः १४. २, २९; ६१.
युवतिं २०. ८९, ५.
युवतिः १९. ४९, १; ८.
युवतिम् १८. ३, ३.
युवती इर्ति १०. ७, ६; ४२.
युवद्रिक् २०. १४३, ७.
युवम् १. २०, २; ३. १, ३; ११, ६; ४. २५, ३; ७. ४३, २; ५४, १; ८. ४, ५; १४. १, ३१; २, ४२; २०. १७, १२; ८७, ७; १२५, ४; १३९, १; १४३, २; ७.
युवसे ६. ६३, ४.
युवा ६. २, ३; १०. ४, १५; १३. १, ११; २०. १४, २; ६२, २.
युवानम् ६. १, २; ७. २, १; ३३, १; ९. ४, २४; १५, ९; १०. ८, ४४; ११. ७, १८.
युवोः ७. ६०, १; २०. १४३, २.
युष्महि ७. ५४, २.
युष्माकम् ८. ९, २२.
युष्मान् १८. ४, ८६.
यूथा २०. ५६, ४.
यूथाऽईव १८. ३, २३; २०. ७०, १४.
यूथे ५. २०, ३; ९. १४, १७; १३. १, ४१.
यूथेषु २०. १२६, १५.
यूथ्या ∫ २०. ७३, ५.
यूने २०. २१, १०.
यूपः १२. १, ३८.
यूपान् १३. १, ४७.
यूपे ९. ७, ५.
यूयम् १. २६, ३; ३०, १; ३. १, २; १६, ७; ४. २१, ६; २७, ६; ३७, १२; ५. २१, ११; ६. ११४, १; ११५, १; ११. १, १२; ११, २; २६; १३. १, ३; १८. ४, १०; ८६[२]; १९. ११, ५; ४०, २; २०. १२, ६; १७, १२; ३७, ११; ८७, ७.
युयाः ८. ४, १९.
यूषम् ६. १२२, ४.
ये १. १, १; ६, १४; ७, ३; १५, ३; ४; १६, १; १९, २[२]; ३०, २[२]; ३[३]; ३१, २; २. १२, २; २६, १; २८, १; ३[२]; ३१,

५[२]; ३२, १; ५; ३४, ३; ४; ३५, १; **३.** ५, ६[२]; ७[२]; ६, १; ३; ५; ८, ५; १०, ६; १५, २; १९, ३; २१, १[४]; ७[३]; १०; २६, १; २; ३; ४; ५; ६; **४.** ४, ८; ६, ७[४]; ७, ७; ११, १२; १४, ४; १६, ६; २२, ६; २७, २[२]; ३; ४[२]; ५[४]; ३४, ३; ४; ३५, ७; ३६, ५[२]; ९; ४०, १; २; ३; ४; ५; ६; ७; ८; **५.** ३, १०; ६, २; ९; १७, ६; ७[२]; १७; १८, १०; ११; १९, २; ३[२]; २१, ७; ८; २३, ५[३]; १२; ३०, १२; **६.** ३, २; १३, १; ४१, ३[२]; ४७, ३; ५०, ३[२]; ५५, १; ६३, ३; ६६, १; २; ७६, १; ८०, २; ८४, ४; ९४, १; १०३, ३; १०४, १; २; ११७, ३; १२१, १[२]; **७.** १, १[२]; १३, २; ३५, १; ५७, २; ६४, १; ८५, ४; ८८, ४[२]; १०२, ४; **८.** १, ८; ११; २, २७; ४, ९[२]; १८[२]; २३; ५, ७; ६, १०[२]; ११[२]; १२; १३; १४[२]; १५; १९; २३[२]; २४; ८, १०; ९, २१; **९.** १, ९; २, ४; ५; १०; ११; १६; १७; १८; ४, ८[२]; ५, २; १४[२]; ३०; १३, १९; १४, ३; १९[२]; १५, १; १८; २७; **१०.** १, ९; २, ४; ३, ३; १६[२]; ४, ९[२]; २३[२]; ५, २१; ७, १७[२]; २१; २५; ३८; ८, ४; ९; १७; ३५[२]; ४१; ९, ६[२]; ७[२]; ९; १२[३]; २०; २२[२]; २३; १०, ५; ३०; ३१; ३२; **११.** १, ९; ११; २, २; ७, २१[२]; ८, ८; १२[३]; २२[२]; ९, ११; १५; २६; २७; १०, १०; १३; २४; २५; ११, १; १६[२]; १७; २२[४]; १२, २[३]; ८[२]; १४; २३[३]; २४[३]; **१२.** १, ३७; ४७; ४९; ५०[२]; ५६[२]; ५७; २, २६; २७; ४५; ५१; ३, ६; ४०; ४२; ५१; ४, ११; ५१; ५२; **१३.** १, १८[२]; २८; ३५; **१४.** १, ४६; २, ९[२]; १०; ११; ४६; ५१[३]; ७३; **१५.** १३, २; ४; ६; ८; १०; **१७.** १, ८; **१८.** १, ९; ४४; ४५; ४६[४]; ४७; २, ११; १५; १६[३]; १७[३]; १८; २८[२]; ३४[४]; ३५[२]; ४७; ४९[४]; ३, २०[२]; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४६; ४७; ४८; ५९[३]; ७२[२]; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४; २९; ४०; ४४; ५७[४]; ६८; ७५; ७६; ८६[२]; ८७; **१९.** ६, ११; १२; १४; ११, ४; ५; १८, १; २; ३; ४; ५; ६; ७; ८; ९; १०; २७, ११; १२; १३; ३१, ४; ३४, २; ३५, ५; ३६, ३[२]; ४२, २; ४७, ३; ४८, ५[३]; ४९, ७; ५०, २; ५५, ५; ५८, ६[२]; ६५, १; ६६, १; **२०.** १५, ४; २१, ११; २५, ४; ३०, २; ३७, ९; ५५, २; ७०, १३; ७१, २; ७६, ५[२]; ७७, ६; ८३, २; ८८, २; ९४, ६; ७; ११२, ३[२]; ११५, ३[२]; १२५, २; १३९, ३; १४३, ९.

ये इति **३.** ७, ४; **४.** २६, १; ४[४]; ५[२]; ६[२]; **६.** १३८, ४; **८.** ३, २५; **१०.** ९, १३; १४[३]; १६; १९; २१.

येतिरे **१८.** १, १७.

येन **१.** ९, ३; १३, १; २९, १; ३२, १; **३.** ९, ४; १५, ५; ६; २२, ३[३]; २३, १; ३०, ४; **४.** ११, ६; २२, ५; २३, ५[३]; ६[३]; २४, २[२]; ६; ३५, २; **५.** १९, १४[२]; **६.** ७, १; २; ३; ३०, २; ५७, १; ६८, ३; ८२, २; १०१, २[२]; ११७, १; १२९, २; **७.** ११, १; १३, १; ३९, २; **८.** १, १०; ३, २१; ४, ४; **९.** २, १७[२]; ३, ९;

५, १७^{२}; १५, ७; **१०.** ४, ६; **११.** १, २; ३०; ३७; ४, १; ४; ८; ९; १०; ११; १२; १०, १६; १२, ११; **१३.** १, २३; २, ६; २१; ३, १७^{२}; **१४.** १, १९; ३०; ३६^{३}; ४८; ५८; **१८.** १, ५४; ४, ३; ७; ४४; **१९.** ९, ४; २४, १; ३४, ५; ४९, ५; **२०.** ५, ४; ९, ३^{२}; ४; ३४, ४; ३५, ६; ४७, १८; ४९, ६^{२}; ७; ६१, २; ६३, ७; ८^{२}; ९; ७०, १८; ८०, १; ९४, ९; ११५, २; ११७, २; १३९, ४.

येनऽयेन **४.** २६, ७.

येभिः **६.** ११२, २; ३; **७.** ५७, २; **१०.** ८, ३५; **१४.** १, ३४.

येभ्यः **११.** २, २५; **१२.** १, १५; **१८.** २, १४; **१९.** ५८, ६.

येमानः **२०.** १४३, ३.

येमिरे **२०.** ६२, ७; ११८, ४.

येवाषः **५.** २३, ८.

येवाषासः **५.** २३, ७.

येषन्तम् **४.** ७, ४.

येषाम् **१.** ३०, ४^{२}; **२.** २६, १^{२}; **३.** १९, १; ४; **६.** १२२, २; **७.** ६२, ३; **८.** ६, १५; ९, ३; **१०.** २, ६; ४, २३; **१९.** ५६, ४; **२०.** ९४, ७.

येषु **७.** ६२, ३; **८.** २, २२.

यैः **५.** २१, ८; **११.** ४, ६; ७; **१२.** १, ४७; **१८.** ४, २; ७०^{२}; **१९.** ९, ५.

यो इति **११.** ६, ९.

योः **१.** ६, १; **१८.** १, ५१; **१९.** १०, १; ११, ६.

योक्रम् **७.** ८३, १.

योक्राणि **१४.** २, १६.

योक्त्रैः **३.** ३०, ६.

योक्ष्ये **१९.** १३, १.

योगम् **१९.** ८, २^{३}.

योगाय **१०.** ५, १; २; ३; ४; ५; ६.

योगे **१९.** १३, १; **२०.** ६९, १.

योगेऽयोगे **१९.** २४, ७; **२०.** २६, १.

योग्यम् **८.** ९, ७.

योजना **२०.** १२६, २०.

योजनानि **४.** २६, १.

योजनेषु **९.** १४, ९.

योधन्ति **१२.** ३, २९.

योधयाः **२०.** ८७, ४.

योधीः **५.** २, ३; **२०.** १०७, ६.

योना **९.** १५, १०; **२०.** १४२, ६.

योनिः **३.** २०, १; **४.** ३०, ७; **९.** १५, १२; **१३.** १, १७; **१५.** १५, ७.

योनिम् **१.** ११, ३; ५; **३.** २३, २; ५; **४.** १, १; **५.** १, १; २; ६, १; २५, ५; ९; **६.** ८१, २; **७.** १०२, ५; **८.** ९, २; १२; **१०.** ५, २३; **१२.** २, ३१; **१३.** २, २५; **१८.** ३, ५७; ४, २८^{२}; **२०.** १६, ४; ३०, २; ८८, २; ९६, ११; १२; १४.

योनिषु **१३.** १, १९; **२०.** ६७, ५.

योनेः **५.** २५, १; **७.** ३६, ३; **१४.** २, ४३.

योनौ **२.** १, ५; **३.** १७, २; **५.** १२, ६; **११.** ७, ७; **१४.** १, १९; **१८.** १, ८; ३, ६६; **१९.** ५६, १.

योन्याःऽइव **६.** १२१, ४.

योन्याम् **५.** २५, ८.

योपयन्तः **१२.** २, ३०.

योयुवत् **१९.** ४७, २.

योषणा **१८.** १, १९.

योषणे इति **५.** १२, ६.

योषतः ९. ५, २७.
योषति २०. ५३, ३; ५७, १३.
योषा १४. १, ५६; १८. १, ४; १९. ४९, १.
योषाऽइव १२. ३, २९.
योषाः १८. ४, ६०.
योषाम् १४. २, ३७; २०. १०७, १५.
योषितः १. १७, १; ६. १२२, ५; ११. १, १४; १७; २७.
योषितम् ६. १०१, १.
यौ ४. २५, १[३]; २८, १[२]; २[३]; ३[२]; ४[३]; ५[२]; ६[२]; २९, १; २[२]; ३[४]; ४[२]; ५[३]; ६[४]; ६. २९, २; १२७, २; १४०, १; ७. २६, १[२]; ११५, २; ८. १, ९; ६, १; ९. १, ७; १०. १, २१; ९, १३; १४; १७; १९[२]; २१; १८. २, १२.
यौमि २. २, १.
यौवने १८. ४, ५०.
यौष्ट ३. ३०, ५.
यौष्टम् १४. १, २२.

र

रंस्थाः १४. २, १९.
रंहयः १८. २, ९.
रंह्या २०. ३०, ४.
रक्ष ६. १०७, १; २; ३; ४; ८. ६, २५; १९. ४७, ६.
रक्ष ४. १९, ८; ३८, ६; ७; ८. ३, ९; १९; १२. ३, ११.
रक्षः १. २१, ३; ४. १७, ५; ३७, २; ७. २४, १; ७३, २; ८. २, १२; ३, १०; १३; ४, १; ४; १३; २२; २३; ९. ४, १७; १०. ५, ४९; ११. १, २१; ३२; १२. १, ४९; ३, १४; १५; ४३; १३. ६, ४; १४. १, ५९; १९. ३६, २.
रक्षःऽभ्यः ८. ३, २४; ४, २५.
रक्षःऽहनम् ४. २३, ३; ८. ३, १.
रक्षःऽहा १. २८, १; ८. २, २८; १९. १३, ८; ३३, ४; ४४, ७; २०. ९६, ११.
रक्षत १. ३०, १.
रक्षत ८. २, २०; ११. १२, १५.
रक्षतः १०. ६, १२.
रक्षतात् २०. ८८, २.
रक्षतात् २. १३, १.
रक्षताम् ८. १, १२.
रक्षताम् २. ४, ५; ८. १, १३[३]; २, १५; ६, २०; ९. ३, १९; १०. १, २१; १९. १६, २; २७, १५.
रक्षति ८. ९, १३; १०. २, २७; ६, १८; १०, ११; ११. ७, ८; १०; १७; २२; १२. १, १८; १३. २, ४१.
रक्षतु ८. १, ११; १२[२].
रक्षतु ३. १७, ४; ४. १०, ७; ६. ७९, १; ८. १, ११; १२; ५, १६; २२; १०. ३, १३; १४; १५; १२. ३, २४[२]; १८. ३, ६२; १९. १६, २; १७, १; २; ३; ४; ५; ७; ८; ९; १०; २७, २; १५; ३४, १; ३५, २; ४६, १; २; ३; ४; ५; ६; ७.
रक्षथः ४. २५, १.
रक्षथः ४. २५, ३.
रक्षन् ४. ३८, ५; १९. ४६, २.
रक्षन्तः ८. २, १०.
रक्षन्ति १०. ७, २३; १२. १, ७; १९. ४८, ५.
रक्षन्ति ५. २७, ७; १०. ८, ३६; १३. १, २३.
रक्षन्तु ८. १, ११.
रक्षन्तु ५. ३, ४; २८, १०; ८. १, ७; १४;

९. ५, ३८; ११. १, ३३; १४. २, ७; १९. १६, २[२]; १७, ६; २७, ३; ९; १५[२].
रक्षमाणाः ३. ३०, ७; १८. ४, ७०; २०. १६, १.
रक्षसः २. ९, १; ६. १११, ३.
रक्षसः २. ३, ६; ४. १९, ३; ८. ३, २३; ४, ७; १७; १८; १९; २१; ५, ८; १४. २, ७.
रक्षसाम् २. ३, ६.
रक्षसि १९. ३०, ३.
रक्षसे १७. १, १६.
रक्षस्विनीः ६. २, २; ७. ११९, २.
रक्षांसि १. ३५, २; २. ४, ४; ४. १०, २; २५, ४; ३७, १; ५. २९, ११; ६. ३२, १; ३४, २; ५२, १; ८१, १; ८. ३, ९; १८; २६; ६, १३; ७, १४; ९. १२, १७; ११. ८, १६; ११, १६; १२, १; १२. १, ५०; १४. २, २४; ४१; १९. ३४, ९; ३६, १; ४; ५.
रक्षाः ८. ४, १६.
रक्षाति ३. १२, ८.
रक्षितः १४. १, ५.
रक्षिता १९. ३४, १.
रक्षिता ३. २७, १; २; ३; ४; ५; ६; १४. १, ४; १९. १५, ३.
रक्षितारम् २०. ९१, ६.
रक्षितारौ १८. २, १२.
रक्षितृऽभ्यः ३. २७, १; २; ३; ४; ५; ६.
रक्षित्रे १२. ३, ५५; ५६; ५७; ५८; ५९; ६०.
रक्षीः ५. ७, १.
रघटः ८. ७, २४.
रघुऽपत्वानः २०. १३, २.
रघुऽवर्तनिम् २०. १४०, ३.
रघुऽस्यदः ३. ७, १; १३. ३, १६; २०. १३, २.
रजः ४. १, ४; २५, २; ६. ३३, १; ८. २, १; १०. १, ३२; ३, ९; १२. १, ५७; १३. २, २२; ८, ६; १९. ४७, १; २०. २५, २; ४७, १९.
रजःऽसु २०, १७, ८.
रजतऽनाभिः ८. १४, ११.
रजतऽपात्रम् ८. १३, ६.
रजतम् १३. ८, ६.
रजते ५. २८, १.
रजनि १. २३, १.
रजय १. २३, १.
रजसः ४. २, ३; ५. ११, ५; ६; ६. ३४, ५; ८. २, ९; ९. ३, १५; १४, १९; १०. ८, ३; ४०; १३. २, ८; १९. १०, ५; २०. ७०, ६; १४३, ९.
रजसम् ८. २, १०.
रजसा ९. १४, १४.
रजसाः ११. २, २५.
रजसि १२. १, ६०; १३. १, ११; २, ४३; १८. १, ४६.
रजांसि ७. २६, १; २७, १; ४२, १; ९. १४, ७; १२. १, ५१; १३. १, ७; २, २१; २८.
रज्जुः ४. ३, २; १९. ४७, ७.
रज्ज्वा ३. ११, ८.
रज्ज्वाम् ६. १२१, २.
रण २०. १११, २.
रणन्ति २०. ११०, २.
रणम् २०. १३७, १०.
रणयन्तु ४. २१, १.

रणाय १. ५, १; २. ४, १; ५, ४; २०. ५, ६; ११, ४; ३५, ६; ९; ५३, ३; ५७, १३.
रणेऽरणे ५. २, ४; २०. १०७, ७.
रणेषु ५. २, ५; २०. १०७, ८.
रण्यति २०. १७, ६.
रण्यति २०. २५, ६.
रण्यन्ति २०. ४४, २.
रण्यसि २०. १११, ३.
रण्याम् १२. १, ४३.
रण्याय्यि ९. ३, ६.
रण्वः १८. १, २२.
रत्नऽधाम् ७. १५, १.
रत्नऽधेयाय ६. १४०, २.
रत्नम् ५. १, ७; ७. १५, ४; १८. २, ५३; २०. २१, १; १४३, ४.
रत्ना ७. ३०, १; १८. १, २६.
रथ ६. १२५, ३.
रथऽउपस्थः ८. ८, २३.
रथः ४. १२, ६; २९, ७; ७. ६०, १; ८. ८, २३; १०. ४, १[3]; २०. ७६, २; ९४, २; १४२, ३.
रथःऽइव ५. १४, ५; १३.
रथऽकाराः ३. ५, ६.
रथऽक्रीतम् ११. ८, २३.
रथऽजिताम् ६. १३०, १.
रथऽजूतिम् १९. ४४, ३.
रथम् ६. ३७, १; १२५, २; ८. १, ६; ९. १४, २; ३; ११. २, १८; १३. १, २४; २, ७; ३, १८; १८. १, २५; १९. १३, ५; २०. १२, ३; ३४, ८; ३५, ४; ७२, ४; ७६, ८; ८६, १; ९२, १२; १३; १४०, ३; १४३, १.
रथम्ऽइव ३. १६, ६; २०. १३, ३.
रथऽमुखम् ८. ८, २३.
रथम्ऽतरम् ८. ११, ६; ९; ११. ३, १६; १३. ३, ११; १२; १५. २, २; ३, ५; ४, २; ३.
रथम्ऽतरस्य १५. २, ४.
रथम्ऽतराय १५. २, ३.
रथम्ऽतरे ९. १५, ३.
रथम्ऽतरेण ८. ११, ७.
रथऽयाने ४. ३४, ४.
रथर्व्याः १०. ४, ५.
रथऽवाहनम् ३. १७, ३.
रथस्य १०. ४, २; १२. १, ४७; १३. २, २४; १४. १, ४१; २०. ४७, २१.
रथस्यऽइव ४. १२, ७; १०. १, ८.
रथाःऽइव ३. ९, ५; २०. १०, १; ५९, १.
रथानाम् ७. ९०, १.
रथान्ऽइव ५. १३, ६; २०. ६३, ९.
रथाय १३. २, ६.
रथासः २०. ३४, ७.
रथिऽतमम् २०. १०५, ३.
रथिनः ६. १२६, ३; ११. १२, २४.
रथिनीः २०. ७१, १४.
रथी ४. ३४, ४; ७. ७७, १.
रथीऽइव ७. ६४, १.
रथे ४. १०, ६; ६. ३८, ३; १०. ३, २०; १३. १, २१; २, ८; २३; २०. २३, ९; २६, ५; -३१, १; ३२, २; ४७, ११; २०; ६९, १०; १००, ३; १४३, २.
रथेन १४. १, २०; १९. १३, ८; २०. १४३, ४; ५.
रथेभिः २०. ९२, १६; १०५, ४.
रथेऽस्थाम् २०. ३६, ५.

रथैःऽइव ७. ५२, ३.
रथ्यमि २०. ९८, २.
रथ्या २०. २१, ९.
रथ्याऽइव १८. १, ८; ९.
रद २०. ३५, १२.
रदन्ताम् ११. १२, ८.
रदवसो इति रदऽवसो २०. ८२, १.
रदिते ११. ११, ७; ८; ९; १०; ११; १३; १४; २९.
रधम् १७. १, ६; २४.
रधाम ५. ३, ७.
रध्यतु १७. १, ६.
रध्रस्य २०. ३४, ६.
रन्त २०. ३५, ११.
रन्तिः ३. १०, ६.
रन्त्यः २०. ७६, ३.
रन्त्यम् ६. ३३, १.
रन्धय ४. २२, १; २; ८. ३, ८; १२. १, १४.
रन्धयन् १७. १, २४.
रन्धयन्तु ७. ११४, ३.
रन्धयामि १९. ६६, १.
रन्धयासि ६. ७, २.
रन्धयासि ६. ६, १; ५४, ३.
रन्धीः २०. १८, ५.
रपः ४. १३, २; ३; ५. ४, १०; ६. ५७, ३; ९१, १; २.
रपत् १८. १, १९.
रपामि १८. १, १२.
रपेम १८. १, ४.
रभःऽदाम् २०. ३६, ५.
रभताम् १. ७, ४.
रभथाः ८. २, ७.

रभध्वम् २. १२, ५; ६. ६२, २; ३; ९७, ३; १२. २, २६; २८; १९. १३, ६.
रभन्ताम् ११. १२, ८; १८. ४, १२.
रभस्व १. ७, ६; २. ६, ४; ८. २, १; ३, २; ८; ९. ५, १; २; १०. ३, १; २; ११. १, १४; १८. ३, ७१; १९. ३, २.
रभस्वतः २०. ७१, १२.
रभामहे ४. १७, १; ५. ८, ९; ८. १, ८.
रभे ४. २०, ६; ६. ४८, १; २; ३; ७६, २; १९. ५१, २.
रभेथाम् ११. ११, ३; १२. ३, ७.
रभेमहि २०. २१, ४; ५.
रमतयः ७. ७९, २.
रमताम् ७. १२, ४.
रमतिः ६. ७३, २; ३.
रमते १०. ७, ३७.
रमध्वम् ७. ६२, १.
रमध्वम् ५. १३, ५.
रमन्ताम् ७. १२०, ४.
रमन्ताम् ७. ११६, १; ८. १, १.
रमय १. १, २; २०. ८९, १.
रमसे ३. १८, ३; ५. २२, ९.
रम्बते २०. १२६, १६; १७.
रयिः १. १५, २; १९. ३१, १२; २०. ११९, २.
रयिम् २. ६, ५; ३. ५, २; १२, ५; २०, १; ३; ५; ८; ४. २१, २; २५, ५; ३३, १; ३९, २; ४; ६; ८; ६. ३३, ३; ५४, २; ६५, १; ७. १८, १; २१, ३; ४; ४९, १; ८१, २; ८४, १; ८५, २; ८७, ३; ९. ४, २१; ११. १, ३; ११; १२. २, ४६; १४. १, ४२; २, ४; ६; ३७; १८. ३, ११; १४; ४३; ४४; ४, २९;

४०; १९. ३, ३; ७, ९; ३१, १२; १३; १४; २०. १३, १; १७, १२; ६७, १; ७०, १७; ८७, ७; १४३, ६.

रयिऽस्थानः ७. ८१, २.

रयिऽस्थाम् ७. ४०, १; ४१, २.

रयीणाम् ३. १०, ९; ६. ६२, २; ७. ४१, २; ८४, ४; ८९, ३; ११४, ६; १०. ९, २७; ११. १, ३४; १६. ३, १; ४, १; २०. ८८, ६; १३७, ६.

रय्या ३. १४, १; ६. ७८, २.

ररण २०. १२६, १२.

ररन्तु २०. २४, ८.

ररन्धि २०. २३, ४.

रराणः ५. २७, ११; ७. १२०, २; १३. २, ३३.

रराणा १. १८, २; ७. ९०, २; ९. १, २.

रराध २. ३५, २.

ररास्व ७. २१, २; ७०, १.

रवः ५. १३, ३.

रवेण २०. ८८, १; ४; ५; ९१, ६.

रशना १०. ९, २.

रशनाम् ७. ८३, १.

रशनाऽयमाना १४. २, ७४.

रश्मयः ६. १०५, ३; ७. ११२, १; १०. १०, २०; ११. ७, ११; १३. २, १८; २०. ४७, १५.

रश्मिऽभिः २. ३२, १; ५. ३०, १५; ६. ६२, १; १०८, १; ५; ७. १२, १; ९. १३, २२; १२. १, १५; १३. २, २; ४०; ४, २; ३; ४; ५; ६; ७; ९.

रश्मीन् ४. ३८, ५; ७. ८७, ४; ५; १३. २, १०; १८. १, २७; २८.

रसः १. ५, २; ३. १३, ५; २८, ४; ४. ४, ५; ६. १६, १; ९. ४, ५; १०. ४, १८; १२. ६, ४; १४. २, ५८.

रसम् २. २६, ४; ५; ४. २७, २; ३; ५. १३, २; ३; ८. ४, १०; ९. ८, २; १९. ३१, ९.

रसऽवान् १८. १, ४८; ४, २३.

रसस्य १. २८, ३; ४. १७, ३; १८. २, २४.

रसाः ४. १५, २; १९. ३१, ४; २०. ९१, २.

रसाम् ४. २, ५.

रसाय १८. ४, ८१.

रसे २. २९, १.

रसेन ३. ३१, १०; ४. ३५, ३; ६. ७८, १; १२४, १; ७. ९४, १; १०. ५, ४६; ६, २; २२; ८, ४४.

रसेभ्यः २. ४, ५.

राकाम् ७. ५०, १.

राके ७. ५०, २.

राज ३. ४, १; ६. ९८, २; ११. १, २२; १४. १, ६४.

राजऽअश्वः ६. १०२, २.

राजऽकृतः ३. ५, ७.

राजऽकृता १०. १, ३.

राजतः ७. ५६, १; ५९, २.

राजति १०. १०, २८.

राजति १. १०, १; ६. ३१, ३; ३६, ३; ७. ७७, ६; ८. ५, १३; ११. ७, १६; २०. ४८, ६.

राजतु २. ३६, २.

राजन् २०. ८०, २.

राजन् १. १०, २; १४, २; ३; ३. ४, १; ४. २२, ६; ५. ३, ७; ६. ९९, ३; १२३, ५[२]; १२८, ३; ७. ८८, १; २; ११. १, २६; २, २८; १८. १, ६०; २, १२; ४, ७०; १९. ४४, ८; २०. ९४, २.

राज॑नि ६. ११६, १.

राजन्य ५. १८, १; ३.

राजन्यः ५. १७, ९; १८, २; १२. ४, ३२; १५. ८, १; १९. ६, ६.

राजन्यस्य १०. १०, १८; १२. ४, ३३.

राजन्ये ६. ३८, ४.

राज॑ऽभिः २०. १७, १०; ९४, १०.

राजऽयक्ष्मः ११. ४, ८; १२. ७, ११.

राजऽयक्ष्मात् ३. ११, १; २०. ९६, ६.

राजयातै ६. ९८, १.

राजऽवध्येभ्यः ६. १३, १.

राजसि २०. ६१, २; ६; ६२, १०.

राज॑ऽसु ६. ९८, १; ७. ५२, ७; १९. ६२, १; २०. ८९, १०.

राजऽसूयम् ४. ८, १; ११. ९, ७; १९. ३३, १.

राजसे २०. ५४, १.

राजा॑ १. ३३, २; २. ३२, ४; ३६, ३; ३. ३, ३; ४, ५; १२, ४; १६, २; २२, ३; ४. २, २; ८, १; १६, २; ५; २२, २; ३; ४; ५. १७, २; १९, ६; १०; २१, ११[२]; २३, ११; २५, ६; ६. ८८, १; २; ९८, ३; १०४, ३; ७. ८८, १; १२३, १; ८. ७, १६; २०; १३, ६; १४; ९. १, २२; १२, २; २२; १०. १, २२; ३, ११; ६, १५; ११. ७, १७; १४. १, ४९; ५९; १५. २, १६; २२; १४, ५; ७; १३; १८. १, ३३; ३, ६९; ४, २६; ४३; ५३; १९. ५, १; २०, १; २६, ४; ३३, ४; २०. १२, ७; ३६, ९; ९२, १६; ९३, ३; १०५, ४.

राजा॑ऽइव १९. ४९, ६; २०. १७, २.

राजा॑नः ३. ५, ७; २९, १; ५. १७, १०; १९. ५७, २.

राजा॑नम् ३. २०, ४; ६. १२८, १; ११. ८, २; १८. १, ४०; ४९; ३, १३.

राजा॑नौ १८. १, ५४.

राज्ञः १. १०, १; ३; २५, ३; ४. १६, ३; ४; ६. ६८, १; ३; ९. २, ६; १०. ५, ४४; १४. २, ४९; १५. २, १८; २४; १०, १; १६. ८, २९; १९. ६, १६; १३, १०.

राज्ञाम् २. ६, ४; ४. २२, ५; ६. ४०, २.

राज्ञे २. १३, २; ६. २०, २; ९३, २; १५. २, १७; २३; १८. २, ३; १९. २४, ४; २०. २१, १०.

राज्य॑म् ११. १२, २.

राज्यम् ४. ८, १.

राज्यमि १२. ३, ३१.

राज्यानि ११. ८, १५.

राज्यायि ३. ४, २.

राज्ये १८. ४, ३१; ३२.

राट् ७. ५१, २.

रातऽतमा २०. ३५, १.

रातर्यः ११. १०, २१; २०. ५८, २; ७४, ४.

रातऽहव्यः २०. १४३, ३.

रातऽहव्यम् ३. ३, १.

रातऽहव्या १९. १०, १.

रातऽहव्याय २०. ३७, ६.

राता ७. ४८, ३.

रातिः १. २६, २; ३. ८, २; ७. १८, ४; २०. ६०, २; ९५, ४.

रातिम् १९. ३, ४; २०. १४२, १.

रातिऽसाचः १८. ३, २०; १९. ११, २.

रातौ ६. ३९, २.

रात्र्ये ८. २, २०.

रात्रि ३. १०, ७; १९. ४७, २; ५; ४८, २; ४९, ३; ६; ७.

रात्रि ३. १०, ३; १९. ४७, १; ३; ८; ९; ४८, ३; ६; ४९, ८; ५०, १; २; ४; ६; ७.

रात्रिः १३. ७, २.

रात्रिम् १. १६, १; ३. १०, २; ५. १७, १८; ८. ९, २१; १०. १, ३२; १५. १३, १; ५; ७; १३; १६. ७, ९; १७. १, २५; २६; १९. ४८, ५; ४९, ५.

रात्रिम्ऽरात्रिम् १९. ५०, ३; ५५, १.

रात्री २. ८, २; १५, २; ४. १८, १; ५. ५, १; ६. १२, १; १२८, २; ७. ७२, १; ८४, ३; ११. ६, २१; १५. २, ५; १३; १९; २०; २५; १९. ४९, १; २; ४; ९; २०. १२३, १.

रात्रीऽइव ९. ३, १७.

रात्रीः ४. ११, ११; ११. ७, ३; १५. १३, ९.

रात्रीणाम् ४. ५, ४; ७. ८५, ४.

रात्रीभिः १८. १, १०.

रात्र्या ११. २, १६; १५. १८, ५.

रात्र्याः १३. ३, २६; ७, २; १९. ५६, २.

रात्र्याम् २०. १६, ११.

रात्स्यसि ११. ४, १०.

राथऽजितेयीनाम् ६. १३०, १.

राद्धिः १०. २, १०; ११. ९, २२.

राधः ५. ११, ११; १९. ५, १; २०. १५, १; ३०, ५; ३४, १५; ६५, ३; ७१, ११; ७३, २; ७६, ३; ९३, १.

राधयामि ११. १, १०.

राधसः २०. २७, ४.

राधसा २०. ११६, २.

राधसाम् २०. १०४, ४.

राधसे ७. ४८, ३; २०. २२, ३; २३, ६; ५६, ५.

राधानाम् २०. ४५, २.

राधिषि १. १, ४; ३. २९, ८.

राधे १९. ७, ३.

राध्यताम् १२. १, २.

राध्यम् २०. ६०, १.

राध्यमानस्य ११. ३, ११.

राध्यास्म १९. १५, २.

रामायणी ६. ८३, ३.

रामायाम् १२. २, १९.

रामे १. २३, १.

राम्याणाम् २०. ११, ३.

रायः १९. १०, २.

रायः १. ९, ४; २. १३, ३; २९, २; ३४, १; ३. १०, ३; ८; १४, ६; १५, ८; ५. २७, १०; ६. ५, २; ७. ४१, २; ४९, २; ५२, ६; ९. ४, २२; २४; ११. १, ३४; १८. १, ४३; ४, ४७; ६२; १९. २४, ५; ३१, १३; ५२, १; ५५, १; २; २०. १७, ३; ३६, ३; ५६, ४; ६८, १०; ८२, २; ८९, ९.

राया १४. २, ३६; २०. २१, ५.

राये १८. २, ३७; २०. ५५, १; ६९, १; ७१, १२; १०३, १.

रारंजीति ६. ७१, २.

राविषम् २०. १२६, ५.

राशयः ६. १४२, ३.

राष्ट्रऽदिप्सवः १०. ३, १६.

राष्ट्रऽभृत् ६. ११८, २.

राष्ट्रऽभृतः ७. ११४, ६; १०. ८, १५; १३. १, ३५.

राष्ट्रऽभृत्याय १९. ३७, ३.

राष्ट्रम् ३. ४, १; ८, १; १९, २; ५; ५. १७, ३; ४; १९, ६; ७; ८[२]; ६. ३९, २; ८७, १; २; ८८, २; १२८, १; १३४, १; ७. ३६, १; ८. ९, १३; १०. ३, १२; १०, ८; ११. ७, १७; ९, १७; १८; १२. ३, १०; ६, २; १३. १, १; ४; ५; ८; २०; ३४; ३५; १९. ४१, १.
राष्ट्रस्य ३. ४, २; ५, २; ५. १९, ४; ६. ५४, २.
राष्ट्राणि १९. ३०, ३.
राष्ट्राय १. २९, १; ४; १३. १, १; १५. १०, २; १९. २४, १.
राष्ट्री ४. १, २; ३०, २.
राष्ट्रे ५. १७, १२; १३; १४; १५; १६; १७; १९, १०; १२. १, ८; १३. १, ९.
राष्ट्रेण ६. ७८, २.
रासताम् १९. ७, ४[२]; ४०, ४.
रासन्ताम् १९. ११, ५.
रासमाना १२. १, ४४.
रासीय २०. ८२, १.
रास्व ६. ३९, २; ७९, ३; २०. १०८, ३.
राहुणा १९. ९, १०.
रिक्तऽकुम्भान् १९. ८, ४.
रिच्यते ८. ९, २६; २०. ५९, ३.
रिणन् १३. १, २१.
रिणाति ५. २, १; २०. १०७, ४.
रिणामि ५. १३, १.
रिपः ८. ४, १८; २०. ५९, ३.
रिपुः ८. ४, १०; १९. ४९, ९.
रिप्रम् ६. ५१, २; १०. ५, २३; १२. २, ११; ४०; १६. १, १०; १८. ३, १७.
रिप्रऽवाहः १२. २, ८.
रिप्राणि १२. २, १३.
रिप्रात् १२. ३, ५.
रिफती ३. २८, १.
रिरिचे ९. १५, ३; २०. ३५, ९.
रिरिच्याम् १८. १, ८.
रिरिषः ५. ३, ८; ११. २, २९.
रिरेच ५. १, ३.
रिरेच १८. ३, ४१; २०. ७७, ६.
रिशादसः ७. ८२, १.
रिशादाः २. २८, २.
रिशाम् ११. ११, १५.
रिश्यऽपदीम् १. १८, ४.
रिश्यस्यऽइव ५. १४, ३.
रिषः ८. ३, १.
रिषण्यत २०. ८५, १.
रिषत् १९. ३९, २; ३; ४.
रिषन् २. ६, २; ३. १२, ६; ११. १, २५; ३२.
रिषम् १८. ३, ५२.
रिषाम ३. १५, ८; १३. २, ३७; १४. २, ५०; १९. ५५, १; २; २०. १३, ३.
रिष्टम् ४. १२, २.
रिष्यतः २. १५, १; २; ३; ४; ५; ६.
रिष्यति १४. १, ३०; २, ८.
रिष्याः ८. २, १३.
रिष्याति ६. १०९, २.
रिष्येम ७. १०, ३.
रिहन्ति २०. २३, ५.
रिहन्ति ७. ७७, ३; १८. ३, १८.
रिहाणे इति ५. १, ४.
रीयते १२. २, २६.
रीरमन् २०. ९६, १.
रीरिषः ६. ५१, ३.
रुक्मऽप्रस्तरणम् १४. २, ३०.

रुक्मऽवक्षसः ६. २२, २.
रुक्मा ९. ५, २५; २६.
रुचि॑ः १२. १, २५; १३. ६, २; १७. १, २१.
रुचि॑म् ३. १५, ६.
रुचिषीय १७. १, २१.
रुचे १०. २, १६.
रुच्या॑ १३. २, ३०; १७. १, २१.
रुज १. २१, ३; ७. ५२, ४.
रुजः १६. ३, २; २०. ३६, ६.
रुजन् १. १२, १; ४. ३१, ३; १६. १, २;
२०. ७७, ८.
रुणद्धि॑ ७. ५२, ६; ११. ५, ६; २०. ८९, ९.
रुणद्धि ११. ५, ५.
रुणधा॑महै २०. ७०, १८.
रुतम् ५. ५, ६.
रुदत्यः ११. ११, १४.
रुदन् ८. १, १९.
रुदन्ति १४. १, ४६.
रुद्र॑ २. २७, ६.
रुद्र ६. ९०, ३; ११. २, ३; १३; १५; २६;
२९; १८. १, ४०.
रुद्रः १. १९, ३; ३. २२, २; ६. ३२, २;
९०, १; १४१, १; ७. ९२, १; ८. ५,
१०; १३. ४, ४; ६, ५; १५. ५, ११;
१४, ११; १९. १०, ६.
रुद्रम् ३. १६, १; ११. २, १७; ८, ९; १५.
५, १०.
रुद्रऽव॑न्तम् १९. १८, ३.
रुद्रस्य॑ ४. २१, ७; ६. ४४, ३; ५७, १;
५९, ३; ७. ७९, १; ११. २, १२; ३०;
१२. २, ४७; ४, ५२.
रुद्राः ५. ३, ९; १०; ६. ६८, १; ८. ८,
१२; १०. ७, २२; ११. ८, १३; १२.
२, ६; १९. ९, १०; ११; ११, ४; २०.
९९, १.
रुद्राय॑ ४. ३०, ५; ६. २०, २; ७. ९२, १;
१९. ५५, ५.
रुद्रेण॑ ११. २, ७.
रुद्रेभि॑ः ४. ३०, १; १९. १०, ६.
रुद्रैः १९. १७, ३.
रुधिरम् ५. २९, १०.
रुध्मः १२. ३, ४३.
रुन्द्धि १९. २९, ३^{४}.
रुन्द्धे ५. ११, ३; ९. ५, २२; ६, ९; ९, २;
४; ६; ८; १२. ३, ४१; १५. ११, ४; ६;
८; १०; १३, २; ४; ६; ८; १०.
रुन्धते १३. २, १५.
रुन्धाम् ३. २०, १०.
रुपः १८. ३, ४०.
रुमे॑ २०. १२०, २.
रुरुचुः २०. ७७, ४.
रुरुध्रे ४. ३१, ३.
रुरुहुः ४. १४, १.
रुरोज २०. ८८, ५.
रुरोह १०. २, ८; १३. १, ४^{२}; १५^{३}; २६;
३३; ४५; ३, २६.
रुरोहि॑थ ७. ६७, १.
रुरोहिथ ४. २०, ३; ६. १३९, १.
रुव ५. २०, ३.
रुश॑त् २०. १२३, २.
रुश॑ती ३. २८, १; १४. १, २७.
रुश॑तीम् १२. ३, ५४.
रुश॑न्तः ४. १६, ६.
रुश॑न्तम् १४. १, ३८.
रुशन्ती॑ः ४. २१, ७; ७. ७९, १.
रुश॑मे २०. १२०, २.

रुह १२. २, १७.
रुहः १३. १, ४; ८; ९; २६; ३, २६.
रुहेम ७. ७, १.
रूढ्वा १३. १, ८.
रूपकाः ११. ११, १५.
रूपऽधेयानि २. २६, १.
रूपम् १. २४, १; २. २९, ६; ५. २९, १५; ९. ४, ७; ५, २४; १२, १५; १५, २६; १०. २, १२; ११. ९, १; १२. ३, ३३; ६, ३; १४. १, ५६; ५७; १९. ५६, २; २०. १२३, २.
रूपम्ऽरूपम् १. २२, ३; १९. १, ३.
रूपयोः १०. ८, २३.
रूपऽशः ९. १४, १६.
रूपा २०. ३०, ३.
रूपाः ५. २६, ८.
रूपाणि १. १, १; २४, ४; ४. २०, ५; ५. २५, ५; ६. २०, ३; ७. ६२, ७; ८४, ४; ८५, ३; ९. ४, १; १२. ३, २१; ४, २९; १३. १, ११; २, १०; १४. १, २८; २, ३०; १९. ४९, ४.
रूपाणाम् ९. ४, ६.
रूपाय १०. १०, १; ११. २, ५.
रूपे ९. १४, ७.
रूपे इति १३. २, २८; ४२.
रूपेण ४. ११, ७; ५. २५, १०; ११; १२; १३; १०. ८, ३१.
रूपैः ५. १२, ९.
रूरः ५. २२, १०.
रूरम् ५. २२, १३.
रूराय १. २५, ४; ७. ११६, १.
रूरुपः ४. ७, ३; ५; ६.
रेचि २०. ७७, ५.
रेजन्ते ९. १४, १६.
रेजमानान् २०. ९४, ८.
रेजमाने इति १. ३२, ३.
रेणुऽककाटः ४. २१, ४.
रेणुम् १०. १, १३.
रेतः २. २८, ५; ३४, २; ४. १५, ११; ३४, ४; ५. २८, ६; ६. ११, २; ४९, ३; ८. ९, १३; ९. १, २; ४, ४; ७; २३; १५, १३; १४; १७; १०. २, १७; १०, २९; ११. ७, १२; २५; १०, २९; १२. ३, ३; १४. २, १४; १९. ५२, १.
रेतःऽधाः ५. २५, १.
रेतसः १४. २, ३७.
रेतसा ८. ७, २१; १३. १, १५.
रेभाः ८. ३, १२; १०. ५, ४८.
रेभासः २०. ५४, २.
रेभे ८. ३, २१.
रेरिहतीम् ११. ११, १५.
रेरिहम् ८. ६, ६.
रेवतः २०. ५७, २; ६८, २.
रेवति २०. १२६, १३.
रेवति १९. ४७, ४.
रेवती १९. ७, ५.
रेवतीः ६. २१, ३.
रेवतीः ३. ४, ७; ९. १२, ३; २०. १२२, १.
रेवतीभिः १३. १, ५.
रेवन्तम् २०. ११४, २.
रेवान् २०. ९६, ४.
रेषय ११. १, २०.
रेष्मऽछिन्नम् ६. १०२, २.
रेष्मा १५. २, ७; १४; २०; २७.
रैभी १४. १, ७.
रोगः ६. ४४, १.

रोगऽनाशनम् ६. ४४, २.
रोगम् १. २, ४; २. ३, ३; ४; ५; ३. २८, ५; ६. १२०, ३; ९. १३, १; २; ३; ४; ५; २१; २२.
रोचः १७. १, २१[2].
रोचताम् २०. १७, ९.
रोचते ११. १०, १६.
रोचते १०. ८, २४; ११. ७, २६.
रोचन १३. २, १९; २०. ४७, १६.
रोचनः ४. १०, ६; १४. १, ३८.
रोचनम् १३. १, ३९; २०. ६२, ७.
रोचनऽवत् १३. ३, १०.
रोचना ६. ३१, २; ७५, ३; २०. २६, ४; २८, १; ३; ३९, २; ४; ४७, १०; ४८, ५; ६९, ९.
रोचनात् २०. ७०, ५.
रोचनानाम् ४. १०, २.
रोचनानि १९. ७, १.
रोचने ७. ७७, ४.
रोचनेन २. ६, १.
रोचन्ते २०. २६, ४; ४७, १०; ६९, ९.
रोचमानः ३. ५, ४; ५. २०, ६; १३. २, २८; ४२.
रोचमानम् ११. ७, २३.
रोचमानाम् २०. १०७, १५.
रोचय १२. १, १८; १४. १, ३१.
रोचसे १३. २, ३०[4]; १८. ४, ५९.
रोचसे १३. १, ३६; २०. १४२, ३.
रोदम् ८. ६, २६.
रोदसी ७. ५१, २.
रोदसी इति १. ३२, ३; ३. ३, १; ४. १, ४; २, ३; १४, ४; १६, ५; ५. १, ९; ८. ९, ६; ११. ७, १; १३. २, ३२; ३, ६; १८. १, २९; ३, ६५; १९. १०, ३; २०. ११, १; १२, ३; ३२, १; ३४, १; ४२, २; ६१, ५; ६२, ९; ६४, २; ७७, ५; ८०, १; ८१, १; ९०, १; ९२, २०; १०७, २; ११८, ४.
रोदसी इति १८. १, ३१; ४, ८९; २०. ९१, ११.
रोदेन १४. २, ५९; ६०; ६१.
रोधचक्रे इति रोधऽचक्रे ५. १, ५.
रोपणाः ९. १३, १९.
रोपणाकासु १. २२, ४.
रोपयः ११. २, ३.
रोपीः ५. ३०, १६.
रोमशम् २०. १२६, १६; १७.
रोरवीति १८. ३, ६५; २०. ९०, १.
रोरुवत् २०. १२६, १५.
रोरुवतम् ११. १२, २६.
रोषति २०. ५८, २.
रोह ८. १, ६; १३. १, ३४[2]; १८. १, ६०.
रोह २. ३६, ५; ३. १२, ६; २०, १; ५. २८, १४; ६. ३०, २; ८. १, ८; ९. ५, ९; ११. १, ७; १२. २, १; ३, १४; १३. १, २; ३४[4]; १४. १, ६१; २, २४; ३१; ३९; १८. ३, ७३; ४, ६; ५१; १९. ३३, २; ६५, १.
रोहणी ४. १२, १[3].
रोहत ७. १०२, ४; १२. २, २४; ४८; १८. ३, ६४; ४, १.
रोहति १०. ६, ३३.
रोहति ८. १२, २; १०. ९, ५; १३. ३, २६.
रोहतु ४. १२, ३; ४[3]; ५; १०. ६, ३१; ३२; ३३; १२. १, ३५; १४. २, २२; १८. ३, ६.

रोहन्तः ७. ५५, ७.
रोहन्ति ८. ७, ८; १७.
रोहन्ति ४. १४, ४; १९. ५३, १.
रोहन्तु ६. १०६, १; १२. २, ३१; १८. ३, ५७.
रोहयं ४. १२, १.
रोहय १. ९, २; ४; ६. ६३, ३; ८४, ४; ११. १, ४; ३०; १४. २, ३७; १८. ३, ४.
रोहयत् २०. ३८, ६; ४७, ६; ७०, ९.
रोहयतु १३. १, १३.
रोहयामि १८. ४, १.
रोहसि ५. ५, ३.
रोहात् ११. १, ३०.
रोहान् ४. १४, १.
रोहिणी १३. १, २२; २३; १९. ७, २.
रोहिणी इति ६. ८३, २.
रोहिणीः १. २२, ३[2]; ८. ७, १; १८. ४, ३४.
रोहिणीम् १२. १, ११.
रोहित १३. १, २१; ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.
रोहितः १३. १, १; ३; ४; ५; ६; ७; ८; १०; ११; १३; १४; १५; १८; २४; २५; २६[2]; ३५; ४६; ५२; ५४; २, २५; ३९[4]; ४०[3]; ४१; ३, २६.
रोहितम् १३. १, १३; ३, १२; २३.
रोहितम् ४. ४, ७; ६. १०१, ३.
रोहितस्य १. २२, १; १३. १, ९; २२; २३; ४७; ४८; ४९; ५०; ५१.
रोहिताय १३. १, १३.
रोहिते १३. १, ३७; १४. २, २३.

रोहितेन १३. १, ३४; ५५.
रोहितेभ्यः १९. २२, २३.
रोहितैः १. २२, २.
रोहितौ ५. २३, ४.
रोहेम १९. ६७, ४.
रोहैः १३. १, १३.
रौहिणम् २०. ३४, १३.

ल

लक्षम् २०. ३४, ४.
लक्ष्म १. २३, ४; ६. १४१, २; ३; १२. ४, ६.
लक्ष्मि ७. १२०, १.
लक्ष्मीः ७. १२०, २; ४; ११. ९, १७; १२. ५, ६.
लक्ष्म्यः ७. १२०, ३.
लक्ष्म्यम् १. १८, १.
लघीयसी १०. १, २९.
लघुः ९. ३, २४.
लपन्तु १. ७, ३.
लपिताः ४. ३६, ९.
लब्ध्वा १. ८, २; ५. ८, ८.
लयन्ताम् ४. ३१, ७.
ललाटम् ९. १२, १; १०. २, ८.
ललामम् १५. १, ३.
ललाम्यम् १. १८, १; ४.
लवणात् ७. ८०, १.
लाक्षे ५. ५, ७.
लाङ्गलम् ३. १७, ३; ६.
लाङ्गलेभ्यः २. ८, ४.
लापय १. ७, २; ६.
लार्यम् २०. ८९, १.
लालपीति ६. १११, १.
लिखात् १४. २, ६८.

लिखितम् १२. ३, २२.
लिबुंजा ६. ८, १.
लिबुंजाऽइव १८. १, १५; १६.
लिम्पामि ११. १२, १३.
लोकः ३. २८, ६; ५. ३०, १७; ८. ८, ८; ९. ५, ५; ९; १२, ४; ११. १, ७; ९, १; १२. २, १; ३, ४७; ५, ३; १३. २, ४०; ९, २; १५. ७, ४; ५; १७. १, १८; २०. २०, ४; ५७, ७.
लोकऽकृत् २०. ९५, २.
लोकऽकृतः १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.
लोकऽकृत्नुम् २०. ६१, १.
लोकऽजितम् ४. ३४, ८.
लोकम् २. ९, १; ३. २८, ५; ६; ४. ११, ६; ९; १४, ६; ३४, २; ५. १८, १३; ६. ११९, १; १२०, १; १२१, १; २; ४; १२२, ३; १२३, २; ७. ८८, ४; ८९, २; ८. ९, १५; ९. २, ११; ५, १; ६; १२^{2}; १६^{2}; २२; २६; ६, ९; ७, ६; ११, १३; ११. १, ८; १७; १८; ३१; ३७^{2}; ७, ७; १०, १०; ११; १२. १, १; २, ४५; ३, ७; १६; १७; १९; २६; ३८; ३९; ५३; ४, ३६; १४. १, ५८; ६१; २, १३; १८. १, ५५; २, ८; २५; ४७; ५३; ३, ४; १३; ३८; ७३; ४, २; ७; १०; १३; ४४; १९. १५, ४; ५४, ५^{2}; २०. ९०, २.
लोकाः १५. ६, १७.
लोकाः ४. ३५, ५; ६. ११७, ३; १०. ६, ३१; ७, २२; २९; ३०; ११. ३, १९; १२. ३, २०; १५. १३, २; ४; ६; ८; १०; १८. ४, ४; ५; ६७; १९. ९, १२; ५४, ४.
लोकात् ६. १२०, २; ८. १, ४; ९, १; ९. २, १७; १८; १२. ३, ४५; ४, ५३; ८, ११; १९. ५६, १.
लोकान् ४. ३८, ५; ९. १, २३; ५, १४; १८; ११, १४; १०. ६, १६; ७, ७; १०; ३६; ९, ६; १०; १०, ३३; ११. ५, ३; ७, ४; ६; १२, १२; १२. ३, ६; १५; २५; ३६; १३. १, १६; २, १०; ४२; १९. ६, ८; ५४, ५^{2}.
लोकानाम् १५. ६, १८.
लोकानाम् ४. ३५, १.
लोकाय १०. ५, ७; ८; ९; १०; ११; १२; १३; १४.
लोके २. १०, ७; ३. २९, ४; ४. ११, ४; ३४, २; ५; ६; ७; ६. २६, १; ११७, ३; ११८, २; ७. १०४, १; ८. १, १; ९. ५, ७; ११; १८; १९; १०. ७, २८; ११. १, १९; ३५; ६, ११; १८; १०, १०; १२. २, ९; ३, ३; ४, ३५; १०, ११; १४. १, १९; १५. १२, ७; ११; १६. ९, २; १८. २, २०; ३, ७१; ४, १; ११; ६७; १९. ९, १३.
लोकेन ३. २९, ३; ४; ५.
लोकेषु ९. ११, ११^{2}.
लोगम् १८. ३, ५२.
लोम ४. १२, ५; १२. ४, ८.
लोमशऽवक्षणे ५. ५, ७.
लोमानि ९. ६, २; १२, १५; १०. ७, २०; ९, २; २४; १२. ११, ७.
लोम्ना ४. १२, ५.

लोम्निऽलोम्नि २. ३३, ७; २०. ९६, २३.
लोहितऽआस्यान् ८. ६, १२.
लोहितऽक्षीराः १९. ९, ८.
लोहितम् ९. १२, १७; १०. ९, १८; ११. ३, ७^{२}; ७, २५; १४. २, ४८; १५. १, ७.
लोहितऽवाससः १. १७, १.
लोहितस्य ६. १२७, १.
लोहितेन ६. १४१, २; १५. १, ८.
लोहिनी १२. ३, ५४.
लोहिनीः १०. २, ११.
लोहिनीनाम् ७. ७८, १.
लोहिनीम् १२. ३, २१.
लौक्याः ११. ९, ३; १५. ६, १७.
लौक्यानाम् १५. ६, १८.

व

वंश ३. १२, ६.
वंशानाम् ९. ३, ४.
वंशिषीय ९. १, १४; १६. ९, ४.
वंसगः १८. ३, ३६; २०. ५२, २; ५७, १५; ७०, १४.
वः १. ५, २; ३; १७, ४; ३०, २^{२}; ४^{२}; २. २, ४; १४, २^{२}; ६; २३, १; २; ३; ४; ५; २४, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{२}; ७^{२}; ८^{२}; ३२, ३; ३. २, २^{३}; ८, ४^{२}; ५^{२}; ६; १३, १; २; ३^{३}; ४; ६; ७^{२}; १४, १^{२}; २; ४; ५^{२}; ६^{२}; १९, ७; २६, १^{३}; २^{३}; ३^{३}; ४^{३}; ५^{३}; ६^{३}; २७, १; २; ३; ४; ५; ६; ३०, १; ४; ५; ६^{२}; ७^{२}; ४. १, १; ७, ७^{२}; १५, ७; ९; २१, ६; ७^{२}; ३७, ५; १२; ३८, ७; ५. ६, १; २^{२}; ८, ४; १३, ७; २३, १०; २६, १; ६. २४, ३; ३२, २^{३}; ५५, २; ६४, १; २; ३^{४}; ६६, २; ६७, २; ७३, २^{३}; ३^{३}; ७४, १^{३}; २^{२}; ८३, १; ९४, १^{२}; २; १००, २; १०३, १; ११४, ३; १२२, ५; १२३, १; ७. १३, ४^{३}; ७९, १^{२}; १०२, ४; ११४, ६^{२}; ८. ७, ५^{२}; २१; ९, २२^{२}; ९. २, १४; ४, २४; ५, ११; १०. ५, १; २; ३; ४; ५; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २३; ९, २७; ११. १, ५^{२}; १५^{२}; १८; २७; ११, २; २५^{३}; १२, २; ५; १२. २, २४; ४७; ४८; ४, ४८; १३. १, ३; १४. १, ३२; ३३^{२}; २, १४; १६; १६. १, ६; ८^{२}; ९; १८. १, ५१; ५२; ३, १४; १९; ६४; ४, १; ४८; ६४^{२}; ८१^{२}; ८२^{२}; ८३^{२}; ८४^{२}; ८५^{२}; ८९; १९. १९, १^{२}, २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{२}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; २७, ६^{२}; ५८, ४^{२}; ५९, २; २०. ९, १; १३, २^{२}; १४, ३; ३६, ७; ३९, १; ४९, ४; ५१, १; ५४, ३; ६२, ३; ६४, ६; ६७, २^{२}; ७०, १६; ७३, ३; ७८, १; १०५, ३; १३७, ४; ८.
वक्तरि २. १, ४.
वक्तवे २०. १८, ५.
वक्ता ८. ४, ८.
वक्रः ७. ५८, ४.
वक्रा ७. ५८, ४.
वक्रात् ४. ६, ४.
वर्करी २०. ३६, ५.
वक्षः ११. १, ४.
वक्षणाः २. ५, ५.
वक्षणाभ्यः ७. ११९, १; १४. २, १४.
वक्षणासु ९. ४, १; १३, १६.
वक्षत् १. ३१, ३; १२. २, ४७; ४८; २०. ३६, ७.

वक्षतः २०. २९, २.
वक्षथः २. ३०, २.
वक्षि २०. ६७, ५; ८७, २.
वक्ष्यतः ११. २, २९.
वक्ष्यामि ४. ९, ७,
वघाः ९. २, २२.
वघाऽपते ६. ५०, ३.
वङ्गृदस्य २०. २१, ८.
वर्चः १. २९, ५; ३. ८, २; २४, १; ४. ४, २; ६. २, १; ४, १; ७. ११०, १; १०. १, २८; १३. १, ४३; २०. १५, ४; २५, ३; ४५, १; ६५, २; ११३, १.
वर्चःऽभिः ५. २, ५; १३, १; ८. ४, ८; १९. ३, ४; २०. ७७, ६; १०७, ८.
वचःऽयुजा २०. ३८, ५; ४७, ५; ७०, ८; १००, ३.
वर्चसः ८. ७, ७; १९.
वर्चसा २. ३१, २; ४; ४. ७, ४; ५; ५. ८, ४; १३, ३; २३, २; ६. ८५, २; १०८, ५; ७. ७, २; २२, १; ७८, ३; १९. २६, २.
वर्चसी इति ८. ४, १२.
वचस्युम् १४. २, ६.
वचांसि १९. ३२, ४; २०. १२, १.
वज्र ४. ३१, ६; ३२, १; ६. १३४, ३.
वज्रः २. ३, ६; ३. १, ४; ४. २४, ६; ६. १३४, १; १२. ७, ७; १०, ८; १९. ६६, १; २०. १५, २; ३०, ३; ४; ४७, ३; ९२, १७; ९४, २; १०५, ५; १३७, १४.
वज्रऽबाहुः २०. ३४, १३; १४.
वज्रऽबाहुम् ६. ९७, ३; १९. १३, ६; २०. १२, ६; ९४, ३.
वज्रबाहू इति वज्रऽबाहू ७. ११५, २.
वज्रम् २. ५, ६; ७; ४. २८, ६; ६. १२५, २; १३५, १; १०. ५, ५०; ९, १; ११. १२, १२; १३; २०. ३५, ६; १२; ३६, ९; ७०, १९; ७२, २; ७३, ४; ७५, १; ७७, ७; ९३, ७; १०६, १; १०९, २.
वज्रऽहस्त २०. ६६, ३.
वज्रऽहस्त २०. ३७, ५; ८०, १; ९८, २.
वज्रऽहस्तः २०. ३४, १४.
वज्रऽहस्तम् २०. ३६, ५.
वज्रात् ३. १९, ४.
वज्रिणः २०. ७०, १३.
वज्रिणम् २०. ३१, १; ७०, ११; ९७, १.
वज्रिणा १०. ४, १२.
वज्रिणे ६. २, ३; १८. १, ३७; २०. २२, ६; ७१, १; ९२, ३.
वज्रिन् २०. १८, २; ८१, २; ९२, २१.
वज्रिन् ४. ३२, ६; ७. ७६, १; २०. १५, ६; ३६, १०; ७२, ३; ८१, १; ९२, २०; १३७, ११.
वज्री २. ५, ५; २०. १२, ७; ३८, ५; ४७, ५; ५५, १; ७०, ८.
वज्रेण १. ७, ७; २. १४, ४; ४. ३, ५; २८, ७; ५. २२, ६; २९, १०; ६. ६, २; १३४, २; ८. ५, १५; ११. १२, ३; २७; १२. २, ९; ११, ५; १३. १, ३०; २०. १५, ६; ३५, १०; ११; १०७, ३; १३७, ११.
वञ्चति ४. १६, २.
वञ्चसि १०. ८, २७.
वणिजम् ३. १५, १.
वत्सः ३. १२, ३; ७; १३, ७; ४. १८, २; ३९, २; ४; ६; ८; ८. ९, २; ११, ५;

१३, २; ६; १०; १४; १४, २; ६; १०; १४; ९. ४, ४; १४, ९; १०. ५, १७; १३. १, १०; ३३; २, १३; ३, २६; १८. ४, ३२; २०. १४०, १.
वत्सऽपः ८. ६, १.
वत्सम् ३. १८, ६; ३०, १; ४. २, ८; ७. ७७, ८; ९. १४, १७; १५, ५; ६; १३. १, १०; ३३; ४१; २०. ९, १; २३, ५; ४९, ४; ९२, ८.
वत्सस्य २०. १३८, १; १३९, १.
वत्साः १३. ४, ६.
वत्सान् १२. ४, ७.
वत्सानाम् ९. ४, २; ४.
वत्साम् ४. ३८, ६; ७^{2}.
वत्साय २०. १४१, ५.
वत्से ६. ७०, १; २; ३; ९. १४, ६.
वत्सेन ४. ३९, २; ४; ६; ८; १८. ४, ६.
वत्सौ ८. ९, १.
वद ५. २१, १; ७. ३९, ४; ८. २, ३.
वद १. १०, ४; ३. २०, २; ४. १५, १४; ५. २०, ६^{2}; ११; २१, ३; ६. २९, ३.
वदत ३. ३०, ३.
वदतः ७. ५९, १.
वदति ६. २९, १; १२. १, ४१; २०. २५, ६.
वदति ५. ३०, १६; ९. १०, ८; १२. २, ३८.
वदतु ३. ३०, २; १४. १, ३१.
वदन् १८. ३, ७०.
वदन्तः ३. ३०, ५; ६. ४७, २; १८. १, ४.
वदन्तम् ४. १६, ६; ८. ४, १३.
वदन्ति १०. ८, १७; ११. १, ७; १२. ४, ५१.
वदन्ति ९. १५, २७; २८; १०. ८, १७; ३३; ११. ३, २६; १५. १, ८.
वदन्तीः १०. ८, ३३.
वदन्तीम् ५. २०, ५.
वदन्तु ४. १५, १२.
वदन्तौ १४. १, ३१.
वदाः १२. ३, ५२^{2}.
वदाति ५. २०, ८; १२. ३, १५.
वदानि ७. १३, १.
वदामसि १९. २, ३.
वदामि ६. ६१, २; ३; १२. १, ५८.
वदामि १. ३४, ३; ४. ३०, ३; ४; ५. ३०, २; ३; ४; ७. ३९, ४; ८. ७, ४; १२. १, २९; ५८.
वदासि ५. २०, ६; ८. १, ६; १२. ३, १८; १४. १, २०; २१.
वदिष्यति १. ३२, १.
वदेत् ११. ३, २५; १०, ३.
वदेम १२. १, ५६; २, २२; ३०; १८. ३, २४; २०. ३४, १८.
वधः १. २०, २; ३०, १; ६. ९९, २.
वधकः ८. ८, ३; ४.
वधत्मना ६. ६, ३.
वधत्रैः २०. १३७, ११.
वधम् १. २०, ३^{2}; २१, ४^{2}; ४. १९, ७; ८. ४, ४; २०; २५; ८, १८; ११. १२, १०; १२; १३; १२. १, ३२; १९. २०, १; २०. ६९, ८; ९९, ४.
वधाः ६. १३, १.
वधात् ४. २८, ५; ६. ९३, ३; १०. ३, ७.
वधानाम् ५. २०, ५; ११. १२, २५.
वधाय ५. १४, ९; १७. १, २८.
वध्रिषुः २. २८, ३.
वधीः ७. १२, १^{2}; ८. २, ५; १०. १, २९; २०. २१, ८.

वधीत् ६. ५६, १; ११०, ३; ११२, १; १४२, १.

वधु १४. १, ५८; २, ७.

वधूः १. १४, २; ३. १०, ४; ८. ९, ११; ११. १०, १७; १४. २, २०; २८.

वधूःऽइव ४. २०, ३.

वधूऽदर्शाः १४. २, ७३.

वधूऽपथम् १४. १, ६३.

वधूम्ऽइव ९. ३, २४; १०. १, १.

वधूऽयुः १४. १, ९.

वधूऽयोः १४. २, ४२.

वधेन २. ३१, ३; ५. ३१, १२; ६. ६६, १; ८. ४, १६; १२. १, १४.

वधेयम् १०. ५, १५; १६; १७; १८; १९; २०; २१.

वधैः ८. ८, ३; ४; १०. ५, ४२.

वध्यः १८. २, ३१.

वध्रयः ४. ६, ७; ८; ५. २०, २.

वध्रि ३. ९, २.

वध्रिऽअश्वम् ४. २९, ४.

वध्रिः ४. ६, ७; ८²; १६. ६, ११.

वध्रिम् ३. ९, ३; ६. १३८, ३.

वध्रे ६. १३८, ३.

वध्वः ८. ६, १४; १४. १, २७; २, १०; ४१; ४२.

वध्वै १४. २, ९; ७३.

वनः २०. २२, २.

वनथः २०. १४३, २.

वनन्ति १२. १, ५८.

वनम् ६. ३३, १; ८. ४, २१; २०. ७३, ५.

वनयन्तु ६. ९, ३.

वनर्गुऽभिः ४. ३६, ७.

वनस्पतयः ८. १२, १; १५. ६, २; १९. ९, १४.

वनस्पतिः ४. ३, १; ५. १२, १०; ६. ८५, १; ८. ७, १६; १०. ३, ५; ८; ११; ११. ७, २०; १२. ३, १५.

वनस्पतिऽभ्यः ६. १०, १; १२५, २; १९. ३, १.

वनस्पतीन् १. १२, ३; २४, १; ३. २१, १; ४. २६, ५; ६. २७, २; ८. ८, १४; १२, १; ९. ३, ११; १०. ३, १३; १४; ११. ८, १; ११, २४; २०. ११, १०.

वनस्पतीनाम् १. ३५, ३; ४. ४, ५; ५. २४, २; २५, ७; ८. १२, २; १२. १, ५७; १५. ६, ३; १६. ८, १८.

वनस्पते ५. २७, ११; ६. १२५, १; १२. ३, ३३.

वनस्पते २. ९, १; ६. १२७, १; १४. २, ५०; १८. ३, ७०; १९. ३१, ९; ३४, ९.

वनस्पतौ ३. ५, ३; २०. १३९, ५.

वना १४. २, ७.

वनाः १. ३४, ४.

वनात् २०. ७४, ६.

वनानि ६. ३०, २; ४५, १; २०. १६, १०; ११६, १.

वनिः ५. ७, ३.

वनिनः १९. १०, ५; २०. ६, ७; ११८, ३.

वनिम् ५. ७, २; ६; १२. ४, ११.

वनिष्ठुः ९. १२, १२; १०. ९, १७.

वनिष्ठोः २. ३३, ४; २०. ९६, २०.

वनुताम् ४. १५, १०.

वनुते १२. २, ३६.

वनुते ७. १०८, १.

वनुध्वम् ४. १५, १५.

वनुषः २०. ३०, १.
वनुषे २०. १४३, ३.
वनुष्व १२. ३, ५३.
वने ८. ६, ११; ११. २, २४; १२. १, ४९; १८. १, ३९; २०. ७६, १.
वनेषु २. ३१, ५; १८. २, ३६; १९. ३, २; २०. ११, ३.
वनोति २०. ६७, १.
वन्दध्यै २०. ३५, ५.
वन्दनाऽइव ७. १२०, २.
वन्दमानः ३. १५, ३; ७. ६२, १.
वन्दामहे ३. १७, ८.
वन्दितः १. ७, १.
वन्दे १९. ४९, ३; ५.
वन्द्यः ५. १२, ३; ६. ९८, १.
वन्धुरऽयुः २०. १४३, १.
वन्याय ६. २०, ३.
वन्वताम् ६. १२६, १.
वन्वानः ५. २०, ९.
वन्वे ६. ८२, १; ८. २, १३; २०. ३०, १.
वप ११. १, २६; २९; ३२; १९. ५७, ४.
वपत ३. १७, २; ६. ६८, १; ३; १४. २, १४.
वपतु ३. १७, ३; ६. ६८, २.
वपते ९. १९, २६.
वपन्ति १४. २, ३८.
वपन्ति १९. ३२, २;
वपन्तु १८. १, ४०.
वपसि ८. २, १७.
वपाऽउद्दरः २०. ५, २.
वपामि १२. ३, २२; १८. ४, ५५.
वपुः २०. ९२, १०; १४३, २.
वपुःऽतमे ५. ५, ६.

वपूंषि ५. १, २; ८; ९; ६. ७२, १; १९. ४९, ८.
वप्ता ८. २, १७.
वयः २. १०, ३; ४. २१, ६; २७, ५; ६. २, २; ३६, २; ७. १०१, १; ८. ४, १८; ९. ४, १०; ११. १, ३०; १२. ३, १; ४७; १८. ३, ७३; १९. ३७, १; २; २०. १६, १; १२; १७, ३; ४; २५, ४; ३१, ५; ३३, ३; ३६, ४; ५३, १; ५७, ११.
वयःऽधसः ८. १, १९.
वयःऽधाः ५. ११, ११; ७. ४२, २; ९. १, ८; ४, २२; १२. ३, १४; १३. २, ३३; १८. ४, ३८; ५०; १९. ४६, ६.
वयःऽधै २०. ९१, ११.
वयःऽभ्यः ६. १०, २.
वयःऽवयः १. २२, ३; १२. ३, ४९; १९. १, ३.
वयःऽसु ३. २१, २.
वयतः १०. ७, ४२.
वयति १०. ७, ४३; २०. १४, ४; ६२, ४.
वयम् १. १८, ३; २७, १; ३१, १; ३५, ४; २. ४, १; ११, ३; १९, १; २; ३; ४; ५; २०, १; २; ३; ४; ५; २१, १; २; ३; ४; ५; २२, १; २; ३; ४; ५; ३३, ७; ३. ६, ४; १०, ५; ११^{२}; १५, ७; १६, २; ४; ५; २४, २; २७, १; २; ३; ४; ५; ६; ३१, ११; ४. ३, ४; ४, १; ५, १; १७, ६; ७; १८, ८; ३१, ४; ३२, १; ३३, ४; ३७, २; ५. २, ५; ३, १; ७, ३; १४, ७; ९; ६. २६, २; ४१, १; २; ४७, २; ५५, ३; ५८, २; ६२, २; ८५, २; ९०, १;

२; ११४, १; ११५, १; १३५, २; ३; **७.** १०, ३; १८, २; २१, ३; ३५, १; ५२, ४; ७; ५५, ७; ६३, २; ६७, ३; ७०, २; ७४, १; ७७, १; ११; ७८, ४; ८४, ४; ८५, २; ३; ८६, ५^{२}; ८८, ३; ९५, २; ९७, १; ९८, १; ११४, ६; **८.** ३, २२; ९, १८; **९.** १५, २०; **१०.** ३, ८; ४, ६^{२}; ११; १२; ५, १५; १६; १७; १८; १९; २०; २१; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४२; ९, २७; **१२.** १, ६२; २, १३; ३३; **१३.** १, २९; ५९; २, ४३; ८, २; ५; ६; ९, १; २; ३; **१४.** २, ३६; ५०; ६६; ६७; ६९; **१६.** १, ५; ६, १; ७, ५; **१८.** १, ३६; ५८; २, ५९; ४, ६९; ८७^{२}; **१९.** १५, २; ५०, ३; ५५, ३; ५८, १; २; ५९, २; **२०.** १, १; ३, ३; ६, १; १३, ३; १४, १; १५, ४; १७, १०; १८, १; ४; २३, ७; २७, ६; ३४, १८; ३८, ३; ४७, ९; ५२, १; ५७, १४; ६२, १; ७०, ११; १९; २०^{२}; ७९, २; ८८, ६; ८९, ६; १०; ९४, १०; ९६, ५; २३; ९७, १; १०२, ३; १०७, ८; १२५, ७; १४३, १.

वय॑सः **१२.** १, ५.

वय॑से **६.** ५९, १.

वयां॑सि **५.** २, ५; **८.** ७, २४; **११.** २, २; २४; १२, ८; **१२.** १, ५१; **२०.** १०७, ८.

व॒याम् **१३.** २, ४६.

व॒युना॑ **२०.** ७७, ३.

व॒युना॑नि **२.** २८, २; **४.** ३९, १०; **५.** २०, ९; **२०.** ९४, ७.

व॒युने॑षु **२०.** ९७, २.

वर॑ः **१३.** ९, २.

व॒रः **२.** ३६, ५; ६.

व॒र॒ण॒ **१०.** ३, १६.

व॒र॒णः **६.** ८५, १; **१०.** ३, १; ३; ४; ५; ६; ७; १०; ११; १३; १४; १५; १७; १८; १९; २०; २१; २२; २३; २४; २५.

व॒र॒णम् **१०.** ३, १२.

व॒र॒णऽव॑त्याम् **४.** ७, १.

व॒र॒णेन॑ **१०.** ३, २; ९.

व॒र॒त् **२०.** ७८, ३.

वर॑ते **२०.** ३६, ११.

व॒र॒त्राः **३.** १७, ६; **११.** ३, १०.

व॒र॒दा **१९.** ७१, १.

वर॑म् **१२.** ३, ९; **२०.** ६८, ४.

व॒रम् **२.** ३६, ६.

वर॑म्ऽवरम् **३.** १९, ८; **६.** ६७, २; **११.** ११, २०; १२, २१.

व॒रा **१४.** १, ८; ९.

वरा॑ः **११.** १, १०.

व॒राः **११.** १०, १; २.

व॒राःऽइ॑व **२०.** २५, २.

वरा॑न् **१६.** ६, १०.

वरा॑य **७.** ३, १; **२०.** ७६, ६.

व॒रा॒हः **८.** ७, २३.

व॒रा॒हम् **२०.** ३५, ७.

व॒रा॒ह॒ऽयुः **२०.** १२६, ४.

व॒रा॒हेण॑ **१२.** १, ४८.

व॒राहै॑ः **२०.** ९१, ७.

वरि॑मतः **६.** ९९, १.

वरि॑मन् **२०.** ७६, ७.

वरि॑मा **४.** २५, २.

व॒रि॒माण॑म् **७.** १५, ३.

व॒रि॒म्णः **१२.** ११, ११.

वरिम्णा ४. ६, २; ९. २, २०.
वरिवः २०. ११, ७; १७, ११; ८७, ३; ९४, ११.
वारिष्ठम् २०. ९४, १.
वरीयः १. २, २; २०, ३; २१, ४; ३. ४, ७; ४. १९, ७; ५. १२, ४; ६. ५२, ३; ७. ५२, ४; ५३, १; ६७, १; १२३, १; ९. ४, १९; १२. १, ३२; १९. ७, ५; २०. ३४, २; ८९, ११.
वरिवर्जयन्ती १२. ७, ११.
वरीवर्ति ९. १५, ११; १०. २, ७.
वरीवृतात् ८. ६, २२.
वरुण ७. ८८, २; १९. ४४, ९.
वरुण १. १०, २; २०, ३; २. २८, ५; ४. १५, १२; १६, ६; ७; २९, ५; ५. १, ८; ११, १; ४; ५; ६; ७; १०; ११; ६. ५१, ३; ७. ८८, १; २[2]; ३; ४; १३. २, २१; १४. १, ६२; १८. ४, ६९; ७०; १९. ४४, ८; २०. ४७, १८; ९२, ९.
वरुणः १. ९, १; १६, २; १८, २; ३३, २; २. २८, २; ३. ३, ३; ४, ५; ८, १; २२, २; २७, ३; ४. १६, २; ५; ८[3]; ३१, ७; ३२, २; ५. १३, १; १७, २; १९, १०; २१, ११; २२, १; २४, ४; २५, ६; ६. ४, २; २१, २; ७३, १; ८८, २; ९३, ३; ७. ८६, ६; १२३, १; ९. १२, ७; १०. ४, १६; ६, १५; ११. ७, १४; १५; १२. २, १६; ३, २४; १३. ३, १३; ४, ४; १५. १४, ५; १८. १, १८; ३९; १९. ९, ६; ७; १०, ६; १७, ४; २०, १; २६, ४; ३२, ९; ४४, १०; २०. ९२, ८; १०६, ३.
वरुणऽतेजाः १०. ५, ३३.

वरुणम् १. ३, ३; ३. २१, ८; ४. ४०, ३; ५. १, ९; ७. २६, १; २; ९. १५, २८; ११. ८, २; १८. १, ५४; १९. १८, ४.
वरुणस्य १. १०, १; २५, ३; २. १०, १; २; ३; ४; ५; ६; ७; ८; ४. १६, ३[2]; ४; ६. ३८, ३; ६८, ३; ८५, २; १२५, ३; १३२, १; २; ३; ४; ५; ७. ९५, २; ९. २, ६; ४, ८; १०. ४, १; ५, १०; ४४; १०, २२; २८; १३. २, ३५; १४. १, १९; ५७; ५८; २, ४९; १५. २, १८; १६. ८, २९; १८. १, ७; ३, ६६; १९. १३, १०; २०. १०७, १४; १२३, २.
वरुणात् १. १०, ३.
वरुणानी ६. ४६, १; ७. ५१, २.
वरुणाय ४. ४, १; ६. २०, २; १२. ३, ५७; ४, २६; १४. २, ४६; १५. २, १७; १८. १, ३६.
वरुणेन २. २९, ४; ३. ५, ४; ६, २; १३, २; ७. १०९, १; ९. ३, १८; १९. ५६, ४.
वरुणैः ३. ४, ६.
वरुण्याति ६. ९६, २; ७. ११७, २.
वरूथम् १. ६, ३; ५. ६, १४.
वरूथैः २०. ३७, ७.
वरे ७. ९, १; २०. ९४, १.
वरेण्यः ७. १५, ४; ५५, ६; ७७, ६; १९. १५, ३.
वरेण्यऽक्रतुः ६. २३, १.
वरेण्यम् २०. ६, ५; ११, ८; ७१, ११; १०६, १.
वरेऽयम् १४. १, १५; ३४.
वरेषु २. ३६, १.
वर्चः १. ९, ४; १४, १; २. २९, १; ३. २२, ४[3]; ५. ३, १; १८, ४; ६. ६९, ३;

१२४, ३; ७. १३, ३; १४, १; २; ११९, १; ९. १, ११; १२; १३; १६; १७; १०. ५, ७; ८; ९; १०; ११; १२; १३; १४; ३६; ६, ८; १२. १, ५; २५; ६, २; १०, १०; १४. १, ३५²; २, २९; ५३; १६. १, १३; ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३; १८. ३, १२; १९. ३७, १; २; ४९, ४; ५८, २²; ३.

वर्चःऽधसे ३. २१, ५.

वर्चःऽधाः २. ११, ४.

वर्चसः १९. ५८, १; ३.

वर्चसा २. १३, २; ३. ४, १; ५, १; १३, ५; २०, १०; २२, २; ३²; ६; ४. ८, ५; ६; ६. ५, १; ३८, १; २; ३; ४; ५३, ३; ६८, २; १२९, २; ७. ८७, २; ९४, १; २; ९. १, १४; १५; १०. ५, ४६; ४७; ६, २; २२; १२. १, ७; ९; १३. १, १५; १७; १८; १९; २०; ३, १६; १४. १, ३४; ३५; ३६; २, २; १७. १, ६; ७; २७; २८; १८. २, ५९; ६०; ३, १०; ११; १९. २४, ४; ३१, ७; १२; ३३, ५; ३६, १.

वर्चसे १. ३५, १; २. २८, ५; ४. १०, ७; ५. २८, १३; ६. ६२, ३; ६३, १; १२. २, २८; १९. २६, ३; ४५, ६; ७; ८; ९; १०; ४६, १.

वर्चस्यम् १९. २६, ४.

वर्चस्वतीम् ९. १, १९.

वर्चस्विनम् ३. २२, ३.

वर्चस्वी ५. २८, १०; १९. ४०, २.

वर्चांसि ४. २२, ३.

वर्जय १०. ४, २५.

वर्णः १. २३, २; ११. ३, ८.

वर्णम् ११. १०, १६; १७; २०. ११, ५; ९; ३४, ४.

वर्णेन १. २२, १.

वर्णैः १. २२, २.

वर्तताम् ५. १४, ५; १३; ६. १०२, १; १०. १, १९; ११. ११, २१.

वर्तते ६. १०२, १.

वर्तते १०. ८, ७; ११. ६, २२; १२. २, ५२; १९. ४७, १.

वर्तनिः ७. २२, १.

वर्तनिम् १९. १२, १.

वर्तनी २०. २१, ८.

वर्तय ६. ७७, ३; ८. ४, १९; ११. २, २१.

वर्तयतम् ८. ४, ४; ५.

वर्तयति १९. १२, १.

वर्तयामसि ७. १३, ४; २०. १९, १.

वर्ता २०. २७, ४.

वर्तिः २०. १४१, १; १४२, ३.

वर्त्म १२. १, ४७.

वर्त्मानि ६. ६७, १.

वर्त्रम् १. ३, ७.

वर्धताम् २. २८, १; ६. ३९, १; ७२, २; ३; ७८, १; २²; १०१, १; ७. ५५, ५; ७७, ८; ८७, ३; ९. १५, ५.

वर्धति २०. १०६, २.

वर्धनम् १९. ३०, ४; २०. ३४, १५; ८५, ३.

वर्धना २०. ७३, १.

वर्धन्ताम् ५. २९, १२; ६. १३७, २; ३.

वर्धन्ति २०. १७, ७; १००, २.

वर्धन्ति २०. १७, ३.

वर्धन्तु २०. ६९, ६; १०४, १; ११०, ३.

वर्धन्ते ८. २, २२.

वर्धमानः ३. ११, ४; ५. १, १; ६. ११०, ३; ७. ५५, २; २०. ९६, ९.

वर्धमानम् २. १३, ५.

वर्धमाना १२. १, १३.

वर्धय ६. ३, ३; ७. १७, १.

वर्धय १. ९, ३; २९, १; २. ६, २; ३. २०, १; ५; ४. २२, १; ५. २८, ४; ६. ५, ३; ३९, १; ५४, १; ११. १, २१; १९. ६३, १; ६४, २; २०. ५५, २.

वर्धयत् १२. १, १३.

वर्धयत १. १५, २; १९. १, १; २.

वर्धयन् ४. २१, २; १९. २७, ५.

वर्धयन्तः १७. १, १४; २०. ९१, ९; १०.

वर्धयन्ति ५. २, ९; २०. १०७, १२.

वर्धयन्ति १३. १, ३३.

वर्धयन्ती १९. ५८, १.

वर्धयन्तु २. ६, १; १४. १, ५४; २, १३; १८. ३, १०; १२; १९. १, ३.

वर्धयन्तौ ५. २६, १२.

वर्धयाथ १४. १, ३२.

वर्धयामसि १९. ६४, २.

वर्धयामहे १९. ३२, ३.

वर्धयामि ३. १९, ५.

वर्धसे ५. १, ९.

वर्धस्व ६. १०१, १.

वर्धस्व २०. ३३, १; ११५, ३.

वर्धाम २०. ९४, २.

वर्धाय १८. १, ३१.

वध्रीन् १४. १, ६०.

वर्पऽनीतिः २०. ११, ३.

वर्म १. १९, ४; ५. ६, १३; ८. २, १०; ५, १०; १४; १८[५]; १९; ९. २, १६; ५, २६; १०. ६, २; १४. २, २१; १८. २, ५८; ४, ९; १९. १६, २; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २०, ३; ४[४]; २७, १५; ३०, १; ३; ५८, ४; २०. १८, ६.

वर्मणा ७. १२३, १; १७. १, २७; २८; १९. ४६, ४.

वर्मऽसु १९. ३०, १.

वर्माणि ५. ८, ६; ८. ५, ७; ११. १२, १७; १९. २०, २; ३०, २.

वर्मिणः ११. १२, २३[२].

वर्मिणम् १९. ३०, १.

वर्यै १९. ४९, ३.

ववर्ति ९. १४, १३.

वर्षऽआज्यौ १३. १, ४७.

वर्षतः ४. १५, ४.

वर्षति ५. १९, १५.

वर्षते ११. ६, २.

वर्षन् ९. १०, ७.

वर्षन्ति ९. १, ९.

वर्षन्तु ४. १५, ४; ७.

वर्षन्तु ८. १, ५.

वर्षम् ३. २७, ६; ४. १५, ६; ९; १०; १४; १५; ५. १९, १५; ११. ७, १३; ९, २१; १२. ३, ५३; १३. १, ५३; १५. ७, २; ३.

वर्षऽमेदसे १२. १, ४२.

वर्षयन्ति ४. २७, ५.

वर्षयन्ति ९. १, ९.

वर्षऽवृद्धम् १२. ३, १९.

वर्षऽवृद्धे ६. ३०, ३.

वर्षसि १३. ७, १५.

वर्षस्य ४. १५, २; ३; ४; ९. १२, १४.

वर्षाः ६. ५५, २; १५. ३, ४.
वर्षाणि ८. २, २२; १२. १, ३६.
वर्षायं १२. ३, ६०.
वर्षिष्ठः ४. ९, ८.
वर्षिष्ठम् १९. ४९, २; २०. ७०, १७.
वर्षीयसः ६. १३६, २.
वर्षीयांसम् ९. ७, २; १५. ११, ५.
वर्षेण ११. ६, ५; १७; १२. १, ५२; १३. १, ५२; १८. २, २२.
वर्ष्मं ४. २२, २.
वर्ष्मणा ४. ३०, ७.
वर्ष्मन् ३. ४, २.
वर्ष्मन् ५. २, ७; २०. १०७, १०.
वर्ष्माणम् ७. १५, ३.
वर्ष्याः १९. २, १.
वलः २०. १६, १०.
वलगः १२. ९, १.
वलगम् ५. ३१, ४; १०. १, १८.
वलगिनः १०. १, ३१.
वलगिनम् ५. ३१, १२.
वलम् २. ५, ३; २०. ११, १०; २८, १; २; ३९, २; ३; ८८, ५; ९१, ६.
वलस्य २०. १६, ५; ६; ९; ३४, ३.
वल्गन्ति १२. ३, २९.
वल्गाः १९. ९, ९.
वल्गु ३. ३०, ५; १२. ३, १८; ३२.
वल्गुः २. ३६, १.
ववक्षे २०. ४७, ३; ७७, ५; १३७, १४.
ववक्षे २०. ३५, ९.
ववर्तत् २०. ५५, १.
ववर्तत् २०. १४३, ३.
ववर्ध १८. ३, ६५.
ववृतुः ५. १९, १३.
ववृते १९. ३५, ५.
ववृते ७. २२, १; ९. १४, १४.
ववृत्याम् १८. १, १.
ववृत्स्व ४. ३२, ६.
ववृधध्यै २०. ३५, ३.
ववृधन्तः १८. ३, २२.
ववृधस्व २०. ८, १.
ववृधस्व २०. ३७, ११.
ववृधानः १. ८, ४; ५. २, २; २८, ४; १३. १, ९; १७. १, १२; १८. १, ४७; २०. ११, १; १०७, ५.
ववृधानम् ८. ४, ४; १९. ४५, ३; २०. ३६, ६.
ववृधानस्य २०. २७, ६.
ववृधानाः ७. १, १.
ववृधानाम् १२. १, २९.
ववृधानौ ७. ३०, २; १३. १, ४९.
ववृधुः १८. १, ४७.
ववृधे १४. १, ३७; २०. ७३, ६.
ववृधे ७. ५, २; २०. ६, ७; ५६, १; ७६, ७; ९९, २; १३८, १.
ववृधेते इति ५. १, ५.
ववृधेन्यम् २०. ६४, ६.
ववृध्वांसम् २०. १००, २.
ववृमहे २०. १४, २; ६२, २.
वव्रे २०. ३५, १५.
वव्रम् ८. ४, १७.
वव्रिम् ९. १४, ५; १५, ७.
वव्रिऽवांसम् २०. ७७, ७.
वव्रिऽवांससम् ८. ६, २.
वव्रुरिति वव्रुः २०. ७७, ६.
वव्रे ८. ४, ३.
वश ३. ४, ७.

वशः १५. ११, २; ८; ९.
वशऽतमा १२. ४, ४२.
वशऽनीः १८. २, ५.
वशम् ४. ३१, ३; ५. १९, १५; ८. ९, २४; ९. ४, २१; १५. ११, ८; १९. २७, ८.
वशस्य ११. १०, १७.
वशा १. १०, १.
वशा १०. १०, ६; १२; १३; १४; १५; १७; १८²; २३; २४; २५²; २६; २८; ३०³; ३४; १२. ४, १०; ११; १४; २२; २५; २९; ३०; ३३; ३५; ३६; ३७; ३९; ४२; ४४; ४५; ४६; ४७.
वशाऽअन्नाय ३. २१, ६; २०. १, ३.
वशाऽइव ७. ११८, २.
वशाः १२. ४, ४१; ४३.
वशाऽजातानि १२. ४, ४७.
वशान् ६. ७२, १; ९. ४, २४.
वशानाम् १२. ४, ४२.
वशाऽभोगः १२. ४, १३.
वशाम् १०. १०, २; ४; ५; २६²; २७; ३२; ३३; ३४²; १२. ४, १; १५; १६; १८; २०; २१; २२; २३; २४; ३१; ३४; ३८; ४८; ४९; ५०; ५३.
वशायाः १०. १०, १८; २९; ३०; ३१; १२. ४, ४; ३२; ४०; ५१.
वशायाम् १०. १०, २५.
वशासः ४. २४, ४.
वशिनाम् १५. ११, ९.
वशिनी १४. १, २०.
वशी १. २१, १; ४. १७, ८; २४, ७; ३१, ३; ५. २२, ९; ६. ५, २; २६, १; ३६, २; ८६, २; ८. ५, ४; ७; २२; १०. १०, २४; ११. ७, १६; ८, २१; १५. ११, ९; १९. १३, ४; ४६, ७.
वशीयः १८. ४, ४९.
वशे १. ८, २; ३. २५, ६; ९. १५, २४²; ११. ६, १; १२, ४; १३. ६, ७; २०. ११२, १.
वशे १०. १०, ७²; ८²; ९; १०; ११; १६; १९; २०; २१; २२;
वशेषु ३. ८, ६; ६. ९४, २.
वषट् १. ११, १; ७. १०२, ७²; ८. १२, ६.
वषट्ऽकारः ११. ९, ९; १३. १, १५; ६, ५.
वषट्ऽकारम् १५. १४, १७.
वषट्ऽकारे १०. ३, २२.
वषट्ऽकारेण ५. २६, १२; ९. ७, ५; १५. १४, १८.
वषट्ऽकृतम् ९. ५, १३; ११. १२, १४.
वष्ठि १८. १, २; १३; २०. ६७, ३; ८९, ४.
वसः १९. ३९, ९.
वसति ५. १७, १८; १५. १३, १; ३; ५; ७; ९.
वसति १०. ८, १५.
वसतिम् ७. १०१, १.
वसतु १०. ६, ४.
वसते १९. २०, २.
वसतेःऽइव ६. ८३, १.
वसन्तः ६. ५५, २; १२. १, ३६; १५. ३, ४; १९. ६, १०.
वसन्तान् ३. ११, ४; २०. ९६, ९.
वसन्ताय ८. २, २२.
वसन्ति ७. ८४, २.
वसन्तु ४. १, ५.
वसवः १. ९, १; ३०, १; ३. १, २; ५. २७, ६; ६. ६८, १; ८. १, १६; ८, १२; १०. ७, २२; ९, ८; १०, ३०; ३१; ११. ८, १३; १२. २, ६; १९. ६, ११; ९, ११; ११, ४.

व॒स॒वः ४. २७, ६; ७. ८२, २; १०२, ३.
व॒सव्यैः ७. २७, ८.
वसा॑नः ४. ८, ३; ९. ४, ७; १९, ११; १०. २, ७; ११. ७, ९; ६; १४. २, ४४; १८. २, १०; ४, ३१.
वसा॑ना ३. १२, ९; ९. ३, १७.
वसा॑नाः ६. २२, १; ७. ४१, २; ९. १४, ९; १९, २२; १३. ३, ९.
वसा॑नाम् ९. १, १.
वसा॑ने इति॑ १३. २, ३२; ३, ११.
व॒सा॒म॒सि॒ १९. ४७, ९.
वसि॑ष्ठ १८. ३, १६.
व॒सि॒ष्ठ॒ २०. १२, १.
वसि॑ष्ठः ६. ११९, १; ७. ५९, २; २०. ११७, ३.
वसि॑ष्ठम् ४. २९, ३; ६. २१, २; ४४, २.
वसि॑ष्ठाः १८. ३, ४६.
वसि॑ष्ठासः २०. १२, ६.
वसु॑ १. ९, १; ३. १४, २; ६. ७२, २; ७. ४२, २; ८४, ३; ९९, २; १२०, २; १०. ८, २०; १२. १, ४४; १४. १, २९; २, ८; १६. ९, ४[२]; १८. २, ६०; १९. ५०, ६; २०. ९, ४; २१, ३; ४३, १; २; ३; ५१, ३; ५६, २; ४; ६३, ४; ९९, ४; १२४, २; १२६, ३.
वसुः २०. ७८, २.
व॒सु॒ऽजित् ५. २०, १०.
व॒सु॒ऽजिति॑ १३. १, ३७.
व॒सु॒ऽदाः १२. १, ४४.
व॒सु॒ऽदानः॑ ६. ८२, ३; १९. ५५, ३; ४.
व॒सु॒ऽदाम् २०. ५८, २.
व॒सु॒ऽदेया॑य ३. ४, ४.
व॒सु॒ऽदेयै॑ १३. ६, ५.
व॒सु॒ऽधात॑रः ५. २७, ६.
व॒सु॒ऽधानः॑ ११. २, ११.
व॒सु॒ऽधानी॑ १२. १, ६.
वसु॑नः २०. २१, २.
वसु॑ना ५. २८, ४; ७. १०३, १; २०. २९, १; ८९, २.
वसु॑ऽनीतिः १२. २, ६.
वसु॑ऽपतिम् २०. ७१, १९.
व॒सु॒ऽपत्नी॑ ७. ७७, ८; ९. १९, ५.
वसु॑ऽभिः २. १२, ४; ४. ३०, १; ५. १२, ३; ६. ७३, १; ७४, ३; १९. १०, ६; १७, १.
वसु॑ऽभ्यः ८. ३, ९.
वसु॑म् ७. १०२, ४; २०. ६७, ३.
वसु॑ऽमन्तम् १८. १, २६.
वसु॑ऽमान् १६. ९, ४[२].
व॒सु॒ऽया ४. ३३, २.
व॒सु॒ऽयुम् २०. १४३, १.
वसु॑ऽरुचिः ८. १४, ७.
व॒सु॒ऽवनिः॑ ७. ६२, १; १३. ६, ५.
वसु॑ऽवन्तम् १९. १८, १.
व॒सु॒ऽवित् १८. ४, ४८.
व॒सु॒ऽविद॑म् ३. १६, ६; २०. ८९, ३; ११८, १.
वसू॑नाम् ४. २६, १; २; ३०, २; ७. ७७, ८; ८१, २; ८४, ३; ९. १, ४; १२, ५; १०. ८, ४२; २०. ७०, १९.
वसू॑नि २. ३५, १; ३. ४, २; ४; ४. ३२, ३; ५. ७, ६; ६. ६३, ४; ७. ५०, २; १०२, ३; ४; १२. १, ४४; १९. ५, १; २४, ६; २०. ५८, १; ९०, ३; ९४, ५.
व॒सेत् १२. ४, २७.
वसो इति॑ २०. ५२, २; ५७, १९.
व॒सो॒ इति॑ ७. ५७, २; २०. १८, ४; २३, ७; ८०, २; १०८, २.

वसो॑ः १. १, २; ९. ४, ३; १२. ३, ४१; १९. ५५, २; २०. ९, १; ४९, ४; ७१, १५.
वसो॑ःऽवसोः १९. ५५, ३; ४.
वसौ॑ २०. ५६, ३[२].
व॒स्ता॒म् ७. २८, १; १२३, १.
व॒स्ति॒ऽवि॒लम् १. ३, ८.
वस्ते॑ १०. ८, ३६; १३. ३, १.
व॒स्ते॒ ११. ६, १०; १३. १, १६[२]; ३, ११.
वस्तो॑ः ५. १२, ४; ६. ३१, ३; २०. ४८, ६; ७७, ४.
वस्त्र॑म् १४. २, ४१; ४२.
वस्त्रा॑ ९. ५, २५; १२. ३, २१.
वस्त्रा॑णि ५. १, ३.
वस्त्रे॑ण १८. २, ५२.
व॒स्त्रेन॑ १२. २, ३६.
वस्य॑ः ६. ४७, ३; ७. १०८, १; २०. १४, ३; ४६, १; ६२, ३; ८२, २.
व॒स्य॒ःऽभूया॑य १६. ९, ४.
वस्व॑ः १८. ३, ४३; २०. १७, ३; १२; २७, १; ८७, ६; ७.
वस्वी॑ः २०. १०९, १; २; ३.
वह॑ ५. १२, १; १८. १, ३०.
व॒ह॒ १. ७, १; ७; २. ५, १; ४. २३, २; ५. ४, ६; ८, १; २९, १; ६. ४८, १; २; ३; ७. ११४, २; ९. ५, १७; १०. ९, २५; १२. २, ४२; १४. १, ६२; १६. ६, ३[२]; १८. १, २५; ५६; ५७; २, ८; ३४; २०. १३, ४; १०१, ३.
वह॑ः ४. ११, ८; ९. १२, ३.
व॒ह॒त् १. ८, १.
व॒ह॒त॒ ५. २६, ४; ७. ९४, ३; १८. २, २७.
वह॑तः २०. ७३, ४.
व॒ह॒त॒ः २०. ३१, १.
वह॑तम् १. २७, ४.
व॒ह॒त॒म् ३. ११, ६.
व॒ह॒ता॒त् ६. ८२, २.
वह॑ताम् २०. ३, २; २३, ९; ३८, २; ४७, ८.
व॒ह॒ता॒म् ३. २४, ७; १४. १, २०.
वह॑ति १३. १, २१; २०. १४३, १.
व॒ह॒ति॒ ९. १४, २; १०. २, ९; ८, ८; १३. ३, १८; १९; १९. ५३, १; २; २०. ८९, ८.
व॒ह॒तु॒ ९. ४, ३; १२. २, ८; १९. ४, १.
व॒ह॒तुः १४. १, १३.
व॒ह॒तुना॑ १४. २, १.
व॒ह॒तुम् ३. ३१, ५; १४. १, १४; ६१[२]; २, ९; १०; १२; ७३; १८. १, ५३.
व॒ह॒तौ १०. १, १; १४. २, ६६.
वह॑न्तम् ११. २, २९.
वह॑न्ति १३. २, ४; ६; ७; २३; २०. ४७, २०; १४३, २.
व॒ह॒न्ति॒ ४. २७, ४; ८. ९, १६; ९. १४, ३; १४; १९; १३. १, २४; ३६[२]; ४३[२]; २, ११; १६; ३, १६; १८. ४, ४४; २०. ४७, १३.
व॒ह॒न्तु॒ ३. १६, ६; ७. ५५, ४; ८७, ६; ९. २, ११; १०. ४, २०; ५, २४; १४. २, ७४; १६. १, ११[२]; ६, ७; ११; १८. १, ६०; २, २२; १९. ७, ४; ५; २०. १२, २; ३२, २; ९४, ३.
वह॑मानः १८. १, २४.
वह॑मानाः ७. १०२, ४.
वह॑सि ४. २३, २; ९. ५, १७.
वह॑से ७. ४, १.
व॒हा॒त् १९. ३१, १०.
वहा॑ति ६. ५५, १; १८. २, ५३.

वहाथ १. ३०, २; १८. ४, १०.

वहिष्ठम् ४. २३, ३.

वहिष्ठाः १३. २, ६; ७.

वह्नेन ४. ११, ७.

वह्नयः २०. १३८, २.

वह्निः ५. २७, ४; १३. ३, १९; १८. १, २३.

वह्निऽभिः २०. ७०, १.

वह्निम् १२. २, ४७.

वह्नी इति १८. २, ५६.

वह्यम् ४. २०, ३; १४. २, ३०.

वह्यऽशीवरीः ४. ५, ३.

वा १. ४, २; ९, २; १८, ३^{२}; २५, २^{२}; ३^{२}; ३०, १; ४; ३२, २; २. १२, ६; १४, ५; २८, २; ३; ३. ११, २; १३, ६; ४. ८, ५; ९, १०; १२, ७; १८, ५; २६, ७; २७, ५; ३८, ५; ५. १, ७^{२}; ५, ४; १४, ६; ७^{२}; १९, ३; २२, २; ७; २५, ६; ३१, २; ४; ८; ६. ७, १; २९, १; २; १०६, १^{२}; ११३, २; ११६, २; ३; १२०, १; ७. १, १^{२}; १३, ४^{२}; २७, ८; ३९, ५^{२}; ५२, ७; ६७, २; ६८, १; ११३, १; २^{२}; ८. ३, ५; ४, ९^{३}; १४^{२}; १५; १६; १८; ६, १८; ९. ८, ९^{२}; १३, २०; १५, १^{२}; १०. १, ४; ११; १८^{२}; ८, १७; २७; २८^{२}; ९, २६^{२}; १२. २, ४; ३, १३; ३९; ५२; १३. १, ६; ५१; २, ७; ७, १४^{३}; १५^{३}; १७; १४. १, ३६; २, ६२; ६५; १८. १, १६^{२}; २२; ४६; २, ७; १७; २६; ३१; ३, ५५; १९. ३८, २; ३९, ९^{२}; २०. १३, ४; २५, ६^{२}; ६४, ४; ७०, ५; ६^{३}; ७१, २^{२}; ७६, १; ८७, ४; ८९, १०; ९६, ७; १११, १^{२}; २; ३^{२}; ११२, २; १२०, १; २; १२६, ३; १०; १४०, १; ४; १४१, २^{२}; १४२, ४; ६; १४३, ३^{३}.

वाः ३. १३, ३; ४. ७, १; १०. ४, ३; ४; १८. १, ३२; २०. १००, २.

वाःऽइव ३. १८, ६.

वाक् २. १२, ८; ३. १३, ६; ५. १८, ८; ६. ३१, ३; ८. ८, २२; ९. १, १०; २०; १५, २४; २७; ११. १०, ४; २६; १२. ६, १; १६. २, १; ६, ५; १९. ९, ३; ६०, १; २०. ४८, ६.

वाकम् ९. १५, २^{२}.

वाकाः ६. २५, १; २; ३.

वाकेन ९. १५, २.

वाकैः १९. ३, ४.

वाक्षीत् ५. ८, ३.

वाग्वीऽइव ५. २०, ११.

वाघतः २०. १९, २; ८४, २.

वाचः ७. ४४, १; १०. ८, ३३; १३. १, १७; १८; १९.

वाचः १. १, १; ३; ४^{२}; ४. १३, ७; ७. १, १; ८. ३, १२; ९. १५, १३; १४; १५; २७; १०. ५, ४८; १२. १, १६; ३, ५; १६. ६, ६^{२}; १७. १, २९; १९. ४०, १; २०. १३७, ५.

वाचः १. १, २.

वाचम् ३. २०, १०; ३०, २; ३; ४. ६, २; १५, १३; ५. १, २; ७, ४; ६; १०, ८; २०, १; ४; ५; ६; ८; ११; ६. ३४, १; ४९, ३; ६१, २; ६९, २; ११८, ३; ८. ९, ३; ९. १, १९; २, ५; १४, १०; १०. २, ७; ११. १, २; ७, २४; १२. ३, १५; १४. १, ३१; १६. २, २; १९. ४, ४; २०. ११, २; २१, १; ४२, १; ८९, १; ११७, ३.

वाचम्ऽइव २. १, ४.
वाचम्ऽईङ्खयः २०. १३७, ६.
वाचा १. १८, ३; ३४, ३; २. ३१, ३; ३५, ५; ५. ७, ५; ३०, २; ३; ४; ९; ६. ८५, २; ९६, ३; १२१, २; ७. ७३, १; ८. १, ३; ३, ६; ९. ३, २; १०. ७, ३९; १३. १, १३; १६. ६, ५; १८. १, ३०; १९. ५८, ५; २०. ७३, ६; ८९, १; १४२, १.
वाचाऽस्तेनम् ८. ३, १४.
वाचि ५. १२, ११.
वाजः ११. ९, ३; १३. १, २; १८. १, ३३.
वाजऽपेयम् ११. ९, ७.
वाजम् ४. २७, १; १४. २, ७०; १८. १, २२; १९. १२, १; २०. ९, २; ३१, ५; ३४, १८; ३७, ६; ४९, ५; ५२, ३; ५७, १६; ६३, ३; ६९, ७; ७७, ८; ८५, ४; ९१, १०; ९८, २; १२४, ६.
वाजय २०. १६, २.
वाजयत्ऽभिः ७. ५२, ३.
वाजयन्तः २०. ३६, २; ९६, ५; १२५, ३.
वाजऽयन्तः २०. १०, १; ५९, १.
वाजऽयन्तम् २०. १०८, ३.
वाजयन्ति ६. १०१, २.
वाजयामः २०. ६८, ९.
वाजयामसि २०. ४७, १; १३७, १२.
वाजऽरत्ना २०. १४३, ७.
वाजऽरत्नाम् २०. ८९, ७.
वाजऽवत् २०. ७१, १३.
वाजऽसातये ५. ६, ४; ७. ५१, १; १४. २, ७२; २०. १९, ५; १३७, २; १४१, ३.
वाजऽसाते ४. २७, १.
वाजऽसातौ १९. १०, १; २०. ११, ११.
वाजस्य ३. २०, ८; ७. ७, २; २०. ७३, ४; ७८, २; ९८, १.
वाजाः ४. ४, ८; १९. ३१, ११.
वाजान् १२. २, २६; २७; १३. १, २२; २०. १२, ४; ३७, ११.
वाजानाम् २०. ६४, ६.
वाजानाम् २०. ६०, ३; ७४, २.
वाजाय २०. ३१, ४.
वाजिन् ४. ३८, ६; ७; ६. ९२, १; २; ३; १३. १, १.
वाजिनः १. ४, ४; ३. १६, ६; ६. ७२, ३; १९. २, ४; २०. १२१, २; १३७, ३.
वाजिनम् ३. २०, ७; ७. ८५, २; ९०, १; ८. ३, १; १०. ६, ११; १३. २, ७; २०. ४४, ३; ६६, १; ६८, ८; ९.
वाजिना ४. ४, २; ८. ४, ६; ११. २, ७.
वाजिनानि ३. १९, ६; १२. ३, २.
वाजिनि १९. ४७, ४.
वाजिनीः १. ४, ४.
वाजिनीऽवतः ८. ८, ६; १०. ४, ७.
वाजिनीऽवते १८. ३, ५४.
वाजिनीऽवन् ४. ३८, ६; ७.
वाजिनीऽवसुः २०. ३१, ३.
वाजिनीवसू इति वाजिनीऽवसू १४. २, ५; २०. १३९, ४.
वाजिनीवसो इति वाजिनीऽवसो २०. २४, ९.
वाजिनीऽवान् ४. ३८, ५[2].
वाजिऽभिः १९. ३७, १.
वाजी ५. २९, १०; ८. ५, २; ९. २, ७; १९. १३, ५; २०. ६७, १.
वाजे ६. ३८, ३; ४; २०. १४, १; ४५, ३; ६२, १.
वाजेभिः २०. २१, ५; २६, २; ४६, ३; ६९, १.

वाजेऽवाजे १९. २४, ७; २०. २६, १.
वाजेषु २०. १९, ६; २४, ६; ५६, १; ६८, ८; ९; ७०, १०.
वाञ्छ ६. ९, $१^{३}$.
वाञ्छन्तु ४. ८, ४; ६. ८७, १.
वाणीः ९. १५, २; २०. ३८, ४; ४७, ४; ७०, ७; १४२, ४.
वाणीभिः २०. १४०, ४.
वात ४. १३, $३^{२}$.
वातः १. ११, ६; २. १०, ३; ३०, १; ३. २१, १०; २६, ४; ४. ५, २; १५, १६; ५. ३, ३; ५, ७; ९, ७; ६. ६२, १; ९१, २; ७. ७२, १; ८. १, ५; २, १४; ६, १९; ९. २, २४; १०. १, १३; ३, १३; १४; ७, १२; ३४; ३७; ८, ३५; ९, २६; ११. ३, ४; ६, १५; ९, २; १०, ३१; १२. १, ५१; १३. १, ५१; १५. २, ७; १४; २०; २७; १९. ८, ६; १०, ४; २७, २; ७; ४४, ५; ५४, २; ५५, २; २०. १६, $५^{२}$; ७३, ५; ७४, ६.
वातः ४. १३, २.
वातःऽइव ४. ३०, ८; १०. १, १७.
वातऽगोपम् २. १२, १.
वातऽजाः १. १२, ३.
वातऽजूतानि ४. १५, १.
वातऽतेजाः १०. ५, २९.
वातऽपत्नीः २. १०, ४.
वातऽपूः १८. ३, ३७.
वातऽभ्रजाः १. १२, १.
वातम् ३. २०, ७; ६. ८९, २; ११. ८, ६; १८. २, ७.
वातम्ऽआयाः १३. २, ४२.
वातऽरंहसः ११. १२, ३.
वातऽरंहाः ६. ९२, १.
वातवे १०. ७, ४४.
वातस्य ३. १, ५; २, ३; ९. ४, १३; १२. १, ५१.
वाताः १. १५, १; ४. १५, ८; १२. ३, १२; १३. ३, २; १८. १, १७; ३९; २, २१; १९. १, १.
वातात् ४. १०, १; ८. २, ३; ९. १, १; ३; १०.
वातापर्जन्ययोः ६. ९३, ३.
वातापर्जन्या ऽ १०. ४, १६.
वाताय १०. ६, ११; १२; १३; १४; १५; १६; १७.
वाति ४. ५, २; ६. ९१, २; १२. १, ५१.
वातीऽकारस्य ९. १३, २०.
वातीकृतऽनाशनी ६. ४४, ३.
वातीऽर्कतस्य ६. १०९, ३.
वातु ४. १५, १६.
वातु ४. १३, २; ७. ७२, १; ८. २, १४; १९. १०, ४.
वाते ३. २१, ७; ६. ३८, ३; ९२, २; ७. ६८, १; १०२, ८.
वातेन ६. ७२, २; १०. ३, १५; १०, १४.
वातौ ४. १३, २.
वादिषः ६. ४२, ३; ४३, ३.
वादिषुः ६. ११८, ३.
वाधूऽयम् १४. १, २९; २, ४१; ४२.
वानस्पत्यः ५. २०, १; २१, ३; १२. ३, १८.
वानस्पत्याः ३. १०, ५; १२. १, २७; १५. ६, २.
वानस्पत्यान् ३. ६, ६; ८. ८, १४; ११. ११, २४.
वानस्पत्यानाम् १५. ६, ३; १६. ८, १९.

वानस्पत्येषु १४. २, ९.

वान्तु ४. १५, ८; १२. ३, १२; १८. १, ३९; २, २१.

वापय १८. ३, ६.

वापयामसि ६. १८, १.

वापीनाम् १९. २४, ६.

वाम् २. २९, ४; ३०, २; ४. २६, १; ५; २८, १^{२}; २९, १; ६. ७८, ३; १२२, ३; १४०, २; ३; ७. ३०, १^{२}; २^{२}; ६०, २; ७७, १^{२}; २; ४; ५^{२}; ८. ४, ३; ६^{२}; ९. १५, २३; ११. २, १; १२. ३, १; २; ३; ४; ५; ७; ८; ३९; १४. १, १४; १५; २, ५; ३९; ४०; १८. १, ३१; ३, ३८; ३९; ४, ४९; १९. ९, ४; २०. १३, १; ७६, १; १३९, ३; ४; १४०, १; ३; ४; ५^{३}; १४१, ४^{२}; १४३, १; २; ३; ५^{२}; ६; ७; ९.

वामऽदेव १८. ३, १६.

वामऽदेवः १८. ३, १५.

वामऽदेव्यम् ४. ३४, १; ८. ११, ६; १०; १५. २, १०; ३, ५; ४, ५; ६.

वामऽदेव्यस्य १५. २, १२.

वामऽदेव्यायि १५. २, ११.

वामऽदेव्येन ८. ११, ८.

वामम् ४. २२, ४; ६. ९२, ३; ७. ८९, २; १४. १, ४६; २, ९; २०. ८९, ८.

वामया २०. १४०, २.

वामस्य ४. २५, ६; ९. १४, १; ५.

वामि ४. ३०, ८.

वामेन ७. ६२, २.

वायवे ४. ३९, ३^{२}; ६. १०, २; १९. ४३, २.

वायव्यान् १९. ६, १४.

वायव्यानि ९. ६, १७.

वायुः २. २६, १; ३४, ४; ३. ८, १; १२, ४; २०, १०; ४. २५, ५; ३९, ४; ५. २४, ८; ६. ५३, १; १२४, २; १४१, १; ८. १, १५; ९. १२, ४; ८; ११. १२, १६; १२. ११, ११; १३. ४, ३; ७, ४; १४. १, ४; १६. ४, ४; १९. ६, ७; १०, ९; १७, २; १९, २; २७, १; ४३, २^{२}; २०. १२, ४.

वायुऽतेजाः १०. ५, २६.

वायुना ४. ३९, ४; २०. १४१, २.

वायुम् ४. २५, ७; ४०, ६; १८. ४, २९; १९. १८, २.

वायुमत्ऽभिः १२. २, २९.

वायो इति २. २०, १; २; ३; ४; ५; ४. २५, ३; ४; ६.

वायो इति ६. ६८, १; ७. ४, १.

वायोः ४. २५, १; ६. ५१, १; ९. ४, १०; १३. ७, ४.

वारः १०. ४, २^{२}.

वारणः २०. ५३, २; ५७, १२; ९७, २.

वारणी ५. १४, ११.

वारय ११. ११, ५; १२, १९.

वारयातै ४. ७, १; ६. ८५, १; १०. ३, ५.

वारयामहे ६. ८५, २.

वारयिष्यते १०. ३, ४; ६; ७; ८.

वारये ४. ७, १; ६. १२, १; २; ८५, ३; १९. ३६, ६.

वारुणाः ६. १२१, १; ७. ८८, ४.

वार्त्रऽहत्याय २०. १९, १.

वार्यम् १८. १, ४१; ४, ४५; २०. ५६, ६; ९५, ३.

वार्यो ७. १८, ३.

वार्याणाम् १. ५, ४; २०. ६८, १२.

वार्याणि ७. ११, १; १९, ३.

वार्षिकम् ४. १९, १; ५. २२, १३.

वार्षिकीः १. ६, ४.

वार्षिकौ १५. ४, ८; ९.

वावदतः २०. १६, १.

वावदत्ऽभिः २०. ९१, ३.

वावदीतु ६. १२६, ३.

वावशतीः २०. ८८, ५.

वावशाना ९. १, ८; १५, ६.

वाश्यमाना १२. ७, ९.

वाश्राऽइव १२. ३, ३७.

वाश्राः ४. १५, १; ५.

वाश्राःऽइव २. ५, ६.

वासः २. १३, २; ३; ५; ८. २, १६; ९. ५, १४; २९; १०. २, १५; १२. ३, ५१; १४. १, ७; ३०; ४५; ५३; २, ४१; ४२; ५१; १५. २, ५; १३; १९; २५; १८. २, ५७; ४, ३१; १९. २४, ४; ५; ६; ५०, ५; २०. १२३, १.

वासतेयः ८. १०, ७.

वासन्तौ १५. ४, २; ३.

वासयातः १२. ३, ३५.

वासये १५. १३, १३.

वासवस्यं ६. ८२, १.

वासंसः ६. १२४, २; १४. १, २७; २, ५०.

वासंसा ७. ३८, १; १८. २, ५१.

वासांसि ९. ५, २६.

वासिताम्ऽइव ५. २०, २.

वास्तु ७. ११३, १.

वास्तुषु १२. १०, ३.

वास्तूनि ९. २, ४; ९.

वास्तैयीः ११. १०, २८.

वास्तोः ६. ७३, ३.

वास्यां १०. ६, ३.

वाहः २०. ७६, ३.

वाहः ६. १०२, १.

वाहसा २०. १३८, २.

वाहाः ३. १७, ६.

वाहान् ३. १७, ५.

वाहि ४. १३, ३^{२}.

वाहिनीं १०. १, १५.

वि १. १, ३; ४; ७, २; ३; ६; ८, २; १०, १; ११, १; २; ३^{२}; ५^{५}; १९, २; ३; २०, ३; २१, २; ३^{४}; ४; २८, ४^{२}; २. ८, १; २७, ४; ३३, १; २; ३; ४; ५; ६; ७; ३६, ३; ३. १, ५; २, २; ३; ४; ३, १; ४, १; २; ४; ७, २; ४; १०, १; १२; ११, ५; ७; १७, १; २; ५; २५, ६; २९, ८; ३०, ५; ३१, १^{४}; २^{४}; ३^{४}; ४^{४}; ५^{३}; ६^{२}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; ४. १, १^{२}; ४; ५; ३, ७^{२}; ७, २; ४; ८, ४; ९, ४; १०, २; ११, २^{२}; १३, २; ३; १५, ८; १६, ५; १९, ५; २१, ४; ३०, २; ७; ३१, २^{२}; ३२, ३; ३७, ६; ८; ९; ५. ३, २; ४, ८; ६, १^{२}; ७, ६; ७; १२, ४; ५; ११; १३, ६; १७, ४; १७; १८, ४; २०, ४; ९; २२, ६; २५, ९; २७, १०; २९, ६; ७; ८; ९; ६. २, २; २२, १; ३०, २; ३१, २; ३; ३६, ३; ४३, ३^{२}; ४९, २; ५६, १; ६३, १; २; ६६, ३; ८१, २; ८४, ३; ९०, १; ९८, २; ११२, १; २; ३; ११३, २; १२१, १; ४; १२७, ३; १३३, १; १३७, ३; ७. ४, १; १९, १; २६, २; २७, ३; ४; ५; ४३, १; ४४, १; ४५, १; ५२, ३; ६; ५८, ७; ७२, १; ७५, २; ७७, ६^{२}; ७८, ३; ८३, १^{३}; ८६,

२; ८८, ३; ८९, ३^{२}; ९५, २; १२२, १; **८.** १, ९; २१; २, १८; ३, ४; २४; २५; ४, १५; १८; २५; ५, ७; ८; १३; ६, १०; ७, ९; ८, २४; ९, ७; २०; **९.** १, ५; ३, १; २; ३; ४; ५; ८; १३; १४; १८^{२}; २०; ५, ४; ८^{२}; २०; २७; १४, ६; ७; १४; १५; १५, १५; १९; २१; २२; २६; **१०.** १, १९; २, ४; ६; ११; ३, ११; ४, ६; ८; १९; ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ६, १८; २१; ३३; ७, २; ४३^{२}; ८, ५; १३; १९; ३०; ४१; **११.** १, ५; १२; २२; ३१^{२}; २, १; १९; २१; ६, ३; २१; ७, १६; १७; १०, ३१; ३३; ११, २३; २६; १२, १६; **१२.** १, १०; ४८; ५७; २, २२; ३२; ५५; ३, ५; १८^{२}; २८; ३६; ५४; ४, २; १०, ९; ११, ७; १०; **१३.** १, ५; ८; ११; १४; १६; २७^{२}; ४२; २, ९; १०; १८; २२; २७^{२}; २८; ३०; ४१; ३, १६; २२; २५; ४, ७; ११; ५, ६; ७, १३; **१४.** १, १३; २२^{२}; २४; २५; २६; ४६; ५६; ५७; ६४; २, २५; ६४; **१५.** २, १; ९; १५; २१; ६, १; ४; ७; १०; १३; १६; १९; २२^{२}; २४; ९, १; **१७.** १, १६; १८; **१८.** १, ८; ९; १७; १९; ३३; ३९; ५५^{२}; २, ४; ४१; ५३; ३, ९; १८; ३९; ५३; ४, ३; ६९; **१९.** ६, २; ५^{२}; १५, १^{२}; २; २४, ६; २८, ४; ४४, ७; ४६, २; ४७, १; ५३, ५; ६; ५५, ६; ६८, १; **२०.** ४, २; ११, १; १२, ३; ४; १६, ४; ९; १७, ५; ९; २२, १; २३, ८; २७, ५; २८, १; ४; २९, ५; ३५, १०; १२; ३६, ४; ६; ९; ३७, ९; ३८, ६; ३९, २; ५; ४७, ६; १५; १९; ४८, ५; ६; ६१, २; ६६, १; ७०, ९; ७२, २; ७३, ४; ७५, १; ७६, ३; ८; ७७, ५; ६; ८५, १; ४; ८८, १; ४; ८९, ४; ९; ९०, २; ९१, ४; ६; ७^{२}; १२; ९३, ६; ९४, ८; ९५, ४; ९६, १; १७; १८; १९; २०; २१; २२; २३; १०७, ३; १२५, ५; १२६, १; ५; २०; १४२, १^{२}.

विऽअंसम् **२०.** ११, ३.

विऽअकल्पयन् **९.** ४, १५.

विऽअक्तम् **१८.** १, ५५.

विऽअक्ता **२०.** १२६, ५.

विऽअङ्ग **५.** २२, ६.

विऽअङ्गः **७.** ५८, ४.

विऽअचन्ति **४.** २७, २.

विऽअचलत् **१५.** १४, १; ३; ५; ७; ९; ११; १३; १५; १७; १९; २१; २३.

विऽअच्यमानम् **१८.** ४, ३६.

विऽअतृणत् **११.** १०, १८.

विऽअद्वराः **६.** ५०, ३^{२}.

विऽअद्वरी **३.** २८, २.

विऽअधूनुत **५.** १८, १२; १९, ११.

विऽअध्वरम् **२.** ३१, ४.

विऽअध्वे **१३.** २, ३१.

विऽअनत् **५.** २, २; **२०.** १०७, ५.

विऽअल्कशा **१८.** ३, ६.

विऽअवर्तयत् **१०.** ७, २६.

विऽअश्वः **२०.** १४०, ५.

विऽअसर्पः **१२.** १, ५५.

विऽअस्यन् **२०.** ९१, ३.

विऽआकरम् **७.** १२०, ४.

विऽआकरोमि **१२.** २, ३२.

विऽआत्तम् ६. ९६, १; १०. ४, ८.
विऽआत्ते १०. ९, ४२.
विऽआध्यः ७. ११९, २.
विऽआनः १४. १, १२; १५. १७, १; २; ३; ४; ५; ६; ७; १८. २, ४६; १९. ५१, १.
विऽआनम् १०. २, १३; ११. ७, २४.
विऽआनशे ३. ७, ६; ५. ७, ९.
विऽआनाः १५. १५, २.
विऽआनार्य ५. ४, ७; ६. ४१, २.
विऽआपिथ १७. १, १२.
विऽआप्तिः ११. ९, २२.
विऽआप्तिम् ९. ५, १२.
विऽआमे १८. ४, ७०.
विऽआमेन ६. १३७, २.
विऽआम्यऽः ४. १६, ८.
विऽआयामे २. ४, ४.
विऽआल ५. २२, ६.
विऽआवर्तने ६. २६, २.
विऽआवृत्तः १०. ७, ४०.
विऽइव ५. २२, ७; २०. १२६, ७.
विऽईर्त्सन्ती ५. ७, ८.
विऽईर्त्सायै ५. ७, १.
विऽउच्छन्तीः १७. १, ३०; १९. ४९, ६.
विऽउन्दती १८. ३, ७२; ४, ५७.
विऽउषः १३. ३, २१.
विऽउष्टीः ८. ९, १०; १५.
विऽऋद्धयः १४. २, ४९.
विऽऋद्धिः ८. ८, ९; १२. ८, २.
विऽएनसौ १४. २, १६.
विऽऐलवाः १२. १, ४१.
विऽओम ९. १५, १३; १४; ११. १, ३०.
विऽओमन् ५. १७, ६; ६. १२३, १; २; ७. ५, ३; ८. ९, ८; ९. १५, १८; १२. १, ८; १३. १, ४४; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १८. ३, ५८; ४, ३०; १९. ५३, ३; २०. ८८, ४.
विऽओषया ३. २५, ४.
विऽओषा ३. २५, २.
विऽऔच्छत् ३. १०, ४; ८. ९, ११.
विंशतिः ५. १५, २; ९. १४, १३; १९. २२, १७; ४७, ५.
विंशतिम् ४. ३, ३; २०. १२६, १४; २३.
विंशत्या ७. ४, १.
विः १८. १, २१.
विकङ्कतीऽमुखाः ११. १२, ३.
विऽकर्णः ५. १७, १३.
विऽकंसुकः १२. २, १४.
विऽकुर्वते १२. १, ४३.
विऽकृता १२. ३, २२.
विऽकृतानि ९. १४, १६.
विऽकृत्यं २०. १६, ८.
विऽकृत्यमाना १२. ८, १.
विऽकेशः ६. ३०, २.
विऽकेशी ५. १७, ४; ११. ११, ७; १४. २, ६०.
विऽकेश्यऽः १. २८, ४; ११. २, ११; ११, १४.
विऽक्रमणम् १८. १, ४५.
विऽक्रमणेषु ७. २७, ३; २०. १४१, २.
विऽक्रमान् ९. ७, १२.
विऽक्रयः ३. १५, ४.
विऽक्रान्ता ८. ११, १.
विऽक्लिन्दुः १२. ४, ५.
विऽक्लैदीयसीः ७. ८०, १.
विऽक्षरन्ति १३. ३, २.
विऽक्षरम् ६. १०५, ३.

विक्षु २.२, १;८.३, १०;४, १८;९.५, १९.
विऽखनामि १२. १, ३५.
विऽगते ५. २१, १०.
विऽगृह्य ४. १५, १४.
विग्रम् २०. ६८, ४.
विऽग्रीवान् ४. १८, ४.
विऽग्रीवासः ८. ४, २४.
विऽघसे ११. २, २.
विऽघ्नानाः ६. ३२, ३; ८. ८, २१.
विऽचक्रमाणः ७. २७, १.
विऽचक्रमे १. १२, १; १२. १, १०.
विऽचक्रिरे १२. १, ५.
विऽचक्षणः १८. ४, ५८.
विऽचक्षणम् १०. २, १९; १०, ३; १३. २, २३; १८. १, २१; २०. ४७, २०.
विऽचक्षणे ९. १४, १२.
विऽचक्षे २०. ७७, ४.
विऽचर्षणिः २०. २०, ५; ७; ५७, ८; १०.
विऽचर्षणे २०. ५, १; ५२, ३; ५७, १६; १०८, १.
विऽचष्टे २. १०, ४; ७. ८६, १; १३. २, ११; १४. १, २३.
विऽचाकशत् २०. १२६, १९.
विऽचाकशीति १३. ३, १.
विऽचित्तः १३. २, ३१.
विऽचिन्वतीम् ४. ३८, २.
विऽचिन्वन् १०. ८, १२; २०. १२६, १९.
विऽचुक्षुभे ७. ५९, १.
विऽचृतम् ६. ११७, १; ११९, २.
विऽचृतामसि ९. ३, १०.
विऽचृतोः ६. ११०, २.
विऽचृतौ २. ८, १; ३. ७, ४; ६. १२१, ३.
विऽचेतसः २०. २५, १.
विच्यध्वम् ११. १, १२.
विऽछिद्य ६. १३९, ५.
विऽछिन्नम् ६. १३९, ५.
विजःऽइव २०. ३४, ५.
विऽजङ्गहे ५. १९, ४.
विजन्ताम् ४. १५, ३; ११. ११, १२.
विजन्ते ८. ७, १५[२].
विजमाना १२. १, ३७.
विऽजयन्ते २०. ३४, ९.
विऽजयस्य १०. २, ६.
विऽजयाय ४. ३१, ४.
विऽजानता १२. ७, ६.
विऽजानन् ४. ११, ३.
विऽजानात् ९. १४, १५.
विऽजानिः ५. १७, १८.
विऽजाम्नि ७. ८०, २.
विऽजायते ३. २८, १; ९. ३, १३.
विजाऽवति ९. ३, १३; १४.
विऽजृम्भते २०. १२६, १६; १७.
विजेषऽकृत् ४. ३१, ५.
विऽज्ञानम् ७. १३, ३; १५. २, ५; १३; १९; २५.
विट्ऽभ्यः ३. ३, ३.
विड्ढि २. ५, ४.
विततऽअध्वरः ९. ७, १०.
विऽततः ४. २, ४; ३४, ५; ९. ७, ११; १३. २, १४; १८. ४, १३.
विऽततम् २. १, ५; ३५, ५; ९. २, १६; ३, ८; १०. ८, १२; ३७; ३८; १९. ५८, ५; २०. २५, २; १२३, १.
विऽतता ६. १२४, ३.
विऽतताम् १०. ३, ४.
विऽतन्वते २०. १०७, १५.

विऽतपन् १२. २, ४१.
विऽतरम् ५. १२, ४.
विऽतस्थिरे ४. ६, २.
विऽतावर्ति १२. २, ३८; ५२.
विऽतुदायसि २. ३२, ६.
विऽतूर्यै २०. १६, ३.
विऽतृतीयम् ५. २२, १३.
विऽतेनिरे ४. १४, ४.
वित्तऽकाम्या १२. ३, ५२.
वित्तम् १८. ४, ८९.
वित्तम् ४. २८, १.
वित्ता १२. ५, १.
वित्ते १९. ४८, ६.
वित्त्वा ७. १०२, ७; ९. ५, २७; १८. २, २५.
वित्स्व ८. २, ३.
विथुरः १६. ६, ११.
विथुरा २०. ८०, २.
विथुरौ ७. १००, १.
विद ६. १२३, २.
विद्ऽगणेभ्यः १९. २२, १८.
विदत् २०. १६, ११; १७, ४; २२, ६; ३५, ६; ९२, ३.
विदत् १. २०, १[२]; ५. ३, ६[२]; ८. १, १६; २०. ४१, २; १२६, १८.
विदत १८. २, ३१.
विदत्ऽवसुः २०. ११, १.
विदत्ऽवसुम् २०. ७०, २.
विदथं १. ३२, १.
विदथम् ८. १, ६; १२. २, २२; ३०; १४. १, २०; २१; १७. १, १५; २०. ३४, १८.
विदथस्य ७. ७७, ४.
विदथा ५. २०, १२; ९. १४, २२; १८. ३, ७०.
विदथानि ४. २५, १; २०. ७७, ३.
विदथाय १८. १, २०.
विदथे १. १३, ४; १८. १, ३५; ३, १९; २४; २०. ३०, १.
विदथेषु ५. १२, ७.
विऽदधत् १८. ४, ५३.
विऽदधत् ७. ८६, १; १४. १, २३.
विदन् १. १९, १[२]; १२. १, ३२; १४. २, ११.
विदन्त ६. ३२, ३; ८. ८, २१; ११. २, २.
विऽदयते २०. ६३, ४.
विदानः ५. २०, ३.
विदाने इति १८. ३, ३८.
विदाम् ५. ३०, १३.
विदितम् ४. २७, ७; ६. १२, २.
विदितौ ४. २८, २.
विदुः १. ३२, २; ५. ४, २; ६. १०८, ३[२]; ४; ८. ७, २३; २४[३]; २६; ९. १५, १; १८; १०. ७, १०; १७[२]; ११. १०, ७; १४. १, ३; १६; १९. ९, १३; २०. ७५, २.
विदुः ४. ११, ९; १६, १; ५. १८, १४; ९. १५, २७; १०. २, ३२; ७, १७; २१; २७; २८; ८, १४; ४३; १०, ५; १२. ३, ५०; १३. १, ४०; २, १३; १४. १, १६; १९. ३४, ६; ५६, ४.
विऽदुग्धान् ८. ९, १०.
विदुर्षः ११. ५, ५; १२. ४, २२; ९, ८.
विदुर्षा १५. १२, ४; ७; ८; ११.
विदुषाम् १९. ६९, २.
विदुषी ११. १, २४.

विदुषे ८. १९, १; १०. १०, ३२; १२. ४, २३; ४९.
विदे १२. ३, ५४; २०. २२, ४; ५१, १; ९२, १.
विदे ४. ३६, ५.
विदेम १०. ६, ३९.
विदेयम् १९. ४, २.
विऽदेवम् १२. ३, ४३.
विऽदेश्यः ४. १६, ८.
विदेष्ट २. ३६, ३.
विद्धः २. २९, ७.
विद्धस्य ११. २, १३.
विद्धस्यऽइव १०. १, २६.
विद्धा ३. २९, ४.
विद्धि ५. २९, १; ६. १२३, ५; २०. १८, ४.
विद्धि ११. १, ३०; १४. २, ३३.
विद्म १. २, १; ३, १; २; ३; ४; ५; १३, ३; ४. ३१, ५; ५. १३, ७; ६. ४६, २; ७. १३, २; ८१, १; ८. ७, १८; १०. १, २०; १३. ३, २१; १६. ५, १; ४; ५; ६; ७; ८; १९. ५६, ६²; २०. २४, ६; ५६, ५.
विद्म ४. ११, १२; ६. ४६, २; ११. १, २९; १३. ३, २१; १६. ५, ३; ४; ५; ६; ७; १०; १८. १, ३६; १९. ५७, ४.
विद्मनाऽअपसम् ७. ४९, १.
विद्मो इति १. २, १.
विद्यते १९. ४९, ७².
विद्यया ६. ११६, १; ११. ९, १०.
विद्याः ११. १०, २३.
विद्यात् ९. ६, १; १०. ७, २४; ८, २०; ३७²; १०, २³; २७; ११. ३, २३; १०, ३; ७; १२. ४, १६.

विद्यात् ७. ९४, २; ८. ९, ३; ९. १, १९; १०. ९, ४७; ८, २०; ३७; १२. ४, २४.
विद्याम २०. ५७, ३; ६८, ३.
विद्याम १०. ८, २९.
विद्युः ७. ९४, २; ९. १, १९; १०. ५, ४७.
विऽद्युत् ४. १९, ९; ९. १, २१; २, १९; १२, ३; १९, ७; ११. ४, ९; १५. २, २५.
विऽद्युतः ४. १०, १; ९. २, १४; १०. ४, २३; १०, ७; ११. ९, २१.
विऽद्युतः १८. ४, ८९.
विऽद्युतम् ३. २१, ७; १०. १, २३; ११. २, २६.
विऽद्युता ७. १२, १; ६१, १; ८. १, ११; १९. ३०, ९.
विऽद्युताम् १९. ४४, ९.
विऽद्युते १. १३, १; ११. ६, २.
विऽद्योतमानः ९. १०, ७.
विऽद्रधम् ६. १२७, ३.
विऽद्रधस्य ६. १२७, १; ९. १३, २०.
विद्रनः ९. १४, ७.
विद्रलाः १०. १, ९.
विद्वांसः ६. ११५, १.
विद्वांसम् ९. १४, ४; १०. ८, १७; १२. ४, ४३; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; १५. २, ३; ११; १७; २३.
विद्वान् २. १, २; २८, २; ३५, ३; ३. १, १; २; २, १; ४. १, ३; ९, ७; ३९, १०; ५. ११, ६; १२, ९; २०, ९; २९, ५; ३०, ७; ६. ६८, ३; ७६, ४; १११, २; ३; १२२, १; ७. ७७, ९; ११३, १; ९.

३, ३; ७, ७; ९, १; ३; ५; ७; ९; १०; १४, ७; १०. ५, ५०; ८, १२; २०; ४४; ११. १, ४; ७, १०; १०, ३२; १२. २, ९; ३९; १४. १, ५६; १५. १०, १; ११, १; १२, १; १३, १; ३; ५; ७; ९; १७. १, १६; १८. २, ५४; ५७; १९. १५, ४; ५६, १; ५९, २; ३; २०. ७७, ६; ८६, १; ९१, ३; ९६, २.

विऽद्विषतेँ ३. ३०, ४.

विऽद्वेर्षणम् २०. ८५, २.

विऽद्वेषम् ५. २१, १.

विऽधक्षन् १८. २, ५८.

विधतः २०. ५८, २.

विधते २०. १४३, ४.

विऽधत्ता १९. ५८, २.

विऽधमाम् १. १८, ४.

विऽधरंणी ९. १२, ४.

विऽधर्तरिँ २०. ९२, १७; १०५, ५.

विऽधर्ता ३. १६, २; १०. ८, ३६; १३. ४, ३.

विऽधर्मणा १६. ३, ६.

विऽधर्मणि ७. २३, १; ९. १५, १७.

विऽधर्मा १६. ३, २.

विऽधाता ५. ३, ९.

विऽधात्रे ३. १०, १०; १९. ३७, ४.

विधुः ९. १३, २२.

विऽधुम् ९. १५, ९.

विऽधूपायत् ४. १९, ६.

विऽधूर्य १३. २, ८.

विऽधृतिः ४. ३५, १.

विऽधृतीः १९. ५४, ५.

विधेम १. ३१, १; ६. ४१, १; २.

विधेम १. १२, २[२]; ४. २, १; २; ३; ४; ५; ६; ७; ८; ६. ३९, २; ८०, १; ३; ९७, १; ७. ८४, ३; ११४, ६; १०. ४, २३; १८. २, ४९; २०. १, ३; ८८, ६.

विध्यं ५. १४, ९; ११. ११, १२; १९. २८, १०[४].

विध्य ३. २, ५; ५. ८, ९; २०, ३; २९, ४[२]; ८. ३, ५; ६; १२; १७; ६, १७; १०. ५, ४८.

विध्यंत् २०. ३५, ७.

विध्यत १. १९, २; ३. २, ६.

विध्यतम् १. ८, २; ८. ४, ३; ५.

विध्यताम् ८. ६, २४; ११. ११, २३.

विध्यति ५. १८, ८; १५; १५. १, ८.

विध्यतु १. १९, ३; ३. २५, २; ५. ३१, १२.

विध्यामः १. १६, ४.

विध्यांमि ७. ७८, २[२].

विध्यामि ३. २५, १; ३; ७. ७८, १; १६. ७, १[६].

विनक्तु १२. ३, १९; १९. ३४, २.

विऽनंद्धा १०. १, १४.

विऽनिक्ष्वैँ ८. ३, २४.

विऽनिर्हँते ७. ५४, २.

विन्दति १२. ४, ४; ५; ८.

विन्दतु ५. ७, ५.

विन्दतैँ ९. ५, २७; १२. २, ३६; १४. २, ८; २२.

विन्दते ११. ७, १८.

विन्दन्ति १८. ४, ८९.

विन्दन्ते ४. ३६, ६.

विन्दसि २०. १२६, २.

विन्दसे २०. ११४, २.

विन्दस्वं ३. २३, ५.

विन्दस्व ३. २३, ४.

विन्धते २०. १४०, १.

विन्धे २०. ७०, १३.
विपः २०. ८५, ४.
विपःऽचित् ८. ९, ३; ९. ५, १३; १३. २, ३१; १४. १, ५९.
विपःऽचितः ९. १५, १७; १९. ५३, १; २०. ८५, ४; १०४, १.
विपःऽचितम् ६. ५२, ३; ९. ४, २१; ११. २, १७; १३. १, ३९; २, ४; २०. ६८, ४.
विपःऽचिता ६. ९७, २.
विपःऽचिते २०. ६२, ५.
विऽपंके ५. २९, ६.
विऽपक्षसा २०. ३६, ५; ४७, ११; ६९, १०.
विऽपथम् १५. २, ६; १४; २०; २६.
विपथऽवाहौ १५. २, ७; १४; २०; २७.
विऽपरुः ७. ५८, ४.
विऽपरेतन १४. २, २८; २९.
विऽपश्यति ४. ५, ५; ३०, ४; ६. ३४, ४; १०. १०, ३४.
विऽपश्यते १९. ३२, ८.
विऽपश्यन् ९. ५, ३.
विऽपश्यामि १२. १, ३३.
विऽपिपानः २०. ७७, ३.
विऽपिपाना २०. १२५, ४.
विऽपेततुः २०. ३१, ४.
विप्र २०. ६७, ५.
विप्रः ५. ११, ११; ६. २७, २; ९. ५, १३; २०. ५०, २.
विप्रऽजूतः २०. ८४, २.
विप्रम् ३. ३, २; ७. ७४, १; ८. ३, २२; १९. ४४, १; २०. ६७, ३; ९१, २.
विप्रऽराज्ये २०. १०४, २.
विप्रस्य ९. ५, १३; १८. १, २२.
विप्राः ४. १, ५; ५. २, ४; ९. १५, २८; १८. ४, ६१; १९. २, ३; २०. ११, ७; १७, ७; ५४, ३; ८८, १; १०७, ७; १२५, ३; १३८, २.
विप्राः २०. ८९, १.
विप्राय ५. ११, ११; २०. ६२, ५.
विप्रासः १४. १, ३७; २०. ३६, २; ७१, २; ११९, २; १३९, ३.
विऽप्रुषः ९. ५, १९.
विऽबद्धः ५. २०, २; ६. ११२, ३.
विऽबन्धुषु १८. २, ५७.
विऽबबाधे ८. ९, ६.
विऽबर्हेण २. ३३, ७; २०. ९६, २३.
विऽबाधः १९. ३४, ७.
विऽभक्ताः १. ३०, ४; ११. २, ९.
विऽभजन्ति १९. ५०, ६.
विऽभजन्ते ३. २९, १.
विऽभजासि १८. १, २६.
विऽभवः २०. १३, ४.
विऽभाज्य ११. १, १३.
विऽभाज्यमाना १२. ८, १.
विऽभाति १३. २, ४२; ३, १७.
विऽभाती १०. ८, ३०; १९. ४९, ४.
विऽभातीः १४. २, ४३; ४४; १८. ३, २४; १९. १०, १०.
विभावरि १९. ४८, २; ४; ४९, ६; ५०, ७.
विभाऽवा १९. ५२, २.
विऽभासासि १९. २६, ३.
विऽभिद्य २०. ९१, ५.
विऽभिनत्ति २०. ५३, १; ५७, ११.
विऽभिन्दती ४. १९, ५.
विऽभिन्दन् ४. १९, ५.
विऽभु २०. ५८, ४; ७१, ११.

विऽभुः १९. ५२, २.
विभुऽक्रतुम् २०. ९२, १२.
विऽभुम् ४. २३, ४.
विभुमत्ऽभ्यः २०. १३७, १०.
विऽभूः ७. २२, १; १३. ८, २; १५. १५, ६.
विऽभूतयः २०. ६०, ५; ७१, ५.
विऽभूतिः २०. ४५, २.
विऽभृतः १९. ३, १.
विऽभेजिरे १०. ७, २७.
विऽभ्राजन् १३. २, ३३; ४५; २०. ६२, ७.
विऽभ्राष्टिम् २०. ६७, ३.
विऽभ्वम् १८. १, २१.
विऽभ्वीः १८. ३, ६९.
विम् ७. १२२, १.
विऽमदम् ४. २९, ४.
विऽमदाय २०. १४१, ५.
विऽमन्युकः ६. ४३, १.
विऽमन्युकस्य ६. ४३, १.
विऽममे ७. २७, १; २०. ३४, २.
विऽमहसः २०. १, २.
विऽमानः ४. २, ३; १०. ८, ३; ४०.
विऽमानम् ९. ३, १५.
विऽमितम् १३. ३, ८.
विऽमिता १३. १, ७.
विऽमिते १०. ७, ३९.
विऽमिमानः १३. २, ५.
विऽमुक्तः ९. १२, २४.
विऽमुचः ६. ११२, ३.
विऽमृग्वरि १२. १, ३५.
विऽमृग्वरी १२. १, ३७.
विऽमृग्वरीम् १२. १, २९.
विऽमृधः १. २१, १; ८. ५, ४; २२.
विऽमोकः १६. ३, ४.
विऽयतौ १०. ८, १८; १३. २, ३८; ३, १४.
विऽयन्ता ९. १५, १६.
विऽयन्ति ३. ३०, ४.
वियुक्ऽभिः ७. ४, १.
विऽयुनक्ति ८. ९, ३.
विऽयूय २०. १२५, २.
विऽरप्शम् २०. ८८, ३.
विऽरप्शिन् ६. २, २.
विऽरप्शिन् २०. ३६, ६.
विऽरप्शिनम् ५. २९, १३.
विऽरप्शी २०. ६०, ४; ७१, ४.
विऽरवेण २०. १६, ८.
विऽराजः ३. १७, २; ८. ९, १; २; १०; १३. १, ३३; १५. ६, २३; १९. ६, ९.
विऽराजन् ३. १२, ६.
विऽराजन्तम् १९. ४२, ४.
विऽराजम् ८. ९, ७; ९; ९. २, ५; १०. ७, १९; ११. ७, ७; १५. १४, ९.
विऽराजा १५. १४, १०.
विऽराजानि १. २९, ६.
विऽराजे १७. १, २२; २३.
विऽराट् ४. ११, ७; ७. ८९, १; ८. ५, १०; ८, २३; ९, ८; ९; १०, १; ९. ५, २१; १५, २४; ११. ६, १२; ७, १६; १०, ३०; १२. ३, ११; १३. ३, ५; १४. २, १५; ७४; १५. ६, २२; १९. ६, ९.
विऽराधनम् ११. १२, २७.
विऽरिष्टम् ६. ५३, ३; ७. ५९, १.
विऽरुजन् १९. २८, ३.
विऽरुजन्ति ९. १३, १३; १८.
विऽरूपम् ६. ७१, १.
विऽरूपाः २. २४, ४; ३. ४, ७; १८. ४, २३.
विरूपे इति विऽरूपे १०. ७, ६; ४२.

विऽरूपौ ५. २३, ४.
विऽरोचंते ४. २३, ७; २८, १; ७. २६, २; १३. १, ५५.
विऽरोचंनः ८. १३, २.
विऽरोहंतः ४. ४, ३.
विऽलपंन् ६. २०, १.
विऽलिंगी ४. १३, ७.
विऽलिप्ती १२. ४, ४६; ४७.
विऽलिप्त्यम् १२. ४, ४१.
विऽलिप्त्याः १२. ४, ४४.
विऽलीढ्य‌मि् १. १८, ४.
विऽलोहितः १२. ४, ४.
विऽलोहितम् ९. १३, १.
विवंक्ति १८. १, २३.
विवक्ति २. २८, २; ४. १, ३.
विवक्षवंः २. ३०, ३[२].
विऽवदंत् ३. ३, ६.
विऽवरुणाः ८. ७, १०.
विवंस्वतः १८. १, ५३.
विवस्वंतः १८. १, ३५; २०. ११, ७; २१, १.
विवंस्वते १८. २, ३३.
विवंस्वन्तम् ११. ८, २; १८. १, ५९.
विवंस्वान् १८. २, ३२[२].
विवस्वान् १८. ३, ६१; ६२; १९. ९, ७.
विऽवांचः २०. ११, १०; ७३, ६.
विऽवांचसम् १२. १, ४५.
विऽवांचि २०. १२, २.
विऽवावंदत् ९. ४, ११.
विवासत २०. ६१, ४; ६२, ८.
विवासे २०. ४४, ३.
विऽवाहान् १२. ९, ६.
विऽवाहे १२. १, २४; १४. २, ६५; ६६.
विविदे २०. १२५, ३.
विऽविंद्धः ६. ६६, १.
विऽविंद्धा ११. १२, २५.
विविश्याः १८. १, ३.
विवृहात् १८. १, १०.
विवेच ६. ६१, २.
विवेद १४. १, ५९; १८. १, ५०; १९. ३२, ९; २०. ९१, ५.
विवेदिंथ २०. ६१, २.
विवेश ३. २९, ७; ४. ११, १; ३०, ५; ३४, ५; ५. १, २; ७. ८७, ४; ९. १४, २२; १५, १०; १०. २, ३३; ७, ८; ९[२]; ३५; ८, ३; ४०; ११. ६, २०; १२. २, ४३; १३. १, २४; १८. १, २७; २०. ११, ५.
विव्यचंत् २०. ३०, ४.
विऽव्याधिनंः १. १९, १.
विऽव्रंताः ३. ८, ५; ६. ९४, १.
विश ६. ११३, २; ७. ११५, ३; १३. १, १; १४. २, २६; ४०.
विशंः ३. ३, ३; ४, २; ६; ४. ८, ४; २२, ७; ३२, २; ५. १, ३; ६. ६१, २; ८७, १; ९८, २; ७. ९९, १; ९. ४, ९; १०. २, २२; २३; १२. ६, २; १३. १, २; १०; २, २०; १५. ८, २; ९, १; १८. १, २१; १९. ५४, ४; २०. ४७, १७; ७३, ३; १०७, १; १३७, ९.
विशंःऽविशः ४. २३, १.
विशत ११. १, १८; १९. १९, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२].
विशतम् ३. ११, ५; ७. ५५, ५.
विशताम् १. २३, २.
विशति ७. ८०, ४.
विशतु १५. १०, ४.
विशते १४. १, २५; १९. ४७, २; ५४, १.

विशथः ४. २९, १.
विशध्वम् १२. ३, ४.
विशन्ति ६. २, २.
विशन्तु २. ९, ४; १२. ३, ३२; १३. १, १०; १८. २, २९; २०. १३, १; ३०, १; ६९, ९.
विशन्ते ४. २९, २.
विऽशफस्य ३. ९, १.
विशम्ऽविशम् ४. ३१, ४; २०. १७, ६.
विऽशरात् २. ४, २.
विऽशरीकम् १९. ३४, १०.
विऽशसनम् १४. १, २८.
विऽशस्तः ९. ९, ४.
विशस्व १८. ३, ७; १९. २४, ८.
विऽशाखाः ८. ७, ४.
विऽशाखे १९. ७, ३.
विशाति १२. ३, ४८.
विशाथ १४. १, ३३.
विशाम् १. २१, १; ३. ४, १; ४. २२, १; ३; ६. ८८, १; ७. ९२, २; ८. ९, २२; १५. ८, ३; २०. ११, २.
विशाम् ३. २०, २.
विशामि ५. ६, ११; १२; १३; १४.
विशाव १५. १०, ३.
विशि ३. ३, ९; १३. १, ९.
विऽशिखान् ४. १८, ४.
विऽशिर्षः ११. १०, २७.
विशे १४. २, २७.
विशेम ३. १०, ११.
विश्पतिः ४. ९, ६; २२, ३.
विश्पतिम् ९. १४, १; २०. १०१, २.
विश्पते २०. ६, ३.
विश्पत्नी ७. ४८, ३.
विश्पत्न्यै ७. ४८, २.
विश्यानाम् ६. १३, १.
विऽश्रयाति १४. २, ३८.
विऽश्रुतम् १५. २, २६.
विश्वऽअङ्गैः १२. ३, १०.
विश्वऽअङ्ग्यम् ९. १३, ९.
विश्वऽअत् ३. २१, ४; १८. ३, ५५; १९. ५९, २.
विश्वऽअन्नम् ९. ३, १६.
विश्वऽआयु २०. १९, १.
विश्वऽआयुः १८. २, ५५; २०. ७१, १३.
विश्वऽकर्मणा २. ३५, ५; १९. ५८, ५.
विश्वऽकर्मणे १३. १, १४.
विश्वऽकर्मन् २. ३५, ४; ६. १२२, १.
विश्वऽकर्मन् २. ३५, ३.
विश्वऽकर्मा २. ३४, ३; ३५, १; २; ४. ११, ५; १२. १, ६०; १९. १७, ७; २०. ६२, ६.
विश्वऽकर्माणः १२. १, १३.
विश्वऽकर्माणम् १९. १८, ७.
विश्वऽकृत् ६. ४७, १.
विश्वऽगर्भाम् १२. १, ४३.
विश्वऽगूर्तः २०. ३५, ९.
विश्वऽगूर्तम् २०. ९२, १८.
विश्वऽगोत्र्यः ५. २१, ३.
विश्वऽचक्षणम् १८. १, १७.
विश्वऽचक्षसे १३. २, १७; २०. ४७, १४.
विश्वऽचयाः १९. ५६, २.
विश्वऽचर्षणिः ४. ३२, ४; १३. २, २६; १९. ३३, ४.
विश्वऽचर्षणे २०. ७१, ९.
विश्वऽजनीनात् ७. ४६, १.
विश्वऽजन्मनः ११. ६, २३.

विश्वऽजन्यः २०. ९१, १.

विश्वऽजित् ६. १०७, १; २; ३.

विश्वऽजित् ४. ११, ५; ११. ९, १२; १७. १, ११.

विश्वऽजितम् ४. ३९, ७.

विश्वऽजिते ६. १०७, २.

विश्वतः २. ४, २; ७, ३; ३. १६, ७; ४. ३३, ५; ६; ५. ३, २; ७. ९२, २; ९९, ६; ८. ४, ६; ५, २२; ९. १५, १७; १०. ८, १०; ११. २, ८; १७. १, ३०; १९. ६, १; २०, ३; ३२, १०; ३३, १; ३४, ५; ४४, ६; २०. ३६, ८; ३९, १; ६४, १; ७०, १६.

विश्वतःऽधारम् ४. १४, ४.

विश्वतःऽपाणिः १३. २, २६.

विश्वतःऽपृथः १३. २, २६.

विश्वतःऽमुख ४. ३३, ६; ७; ७. ६७, २.

विश्वतःऽमुखः १०. ८, २७; १३. २, २६.

विश्वतःऽमुखम् १९. २७, ७.

विश्वतःऽवीर्यम् ३. ३१, ७.

विश्वतःऽवीर्या ६. ३२, २.

विश्वऽतूः २०. १०५, १.

विश्वऽदर्शतः १३. २, १९; २०. ४७, १६.

विश्वऽदानीम् ७. ७७, ११; ९. १५, २०; १२. १, ७; १८. ३, ५४.

विश्वऽदावन् ४. ३२, ६.

विश्वऽदाव्यः ३. २१, ३; ९; १०. ८, ३९.

विश्वऽदृष्टः ५. २३, ६; ६. ५२, १.

विश्वऽदेवः २०. ६२, ६.

विश्वदेवऽवन्तम् १९. १८, १०.

विश्वऽदेवाः १९. ११, २.

विश्वऽदेवाय २०. ८८, ६.

विश्वऽदेवेभिः ७. १०३, १.

विश्वऽदेवेभ्यः १९. ३९, ५.

विश्वऽदेवैः ४. ३०, १.

विश्वधा ६. ८५, ३; २०. ७३, १.

विश्वऽधायसः ३. २२, २.

विश्वऽधायसम् १२. १, २७.

विश्वधाऽवीर्य ५. २२, ३; १९. ३९, १०.

विश्वऽनाम्नीः ७. ७९, २.

विश्वऽपेशसम् २०. ३५, १६.

विश्वऽभृत् ४. ११, ५; ५. २८, ५.

विश्वऽभेषज ४. १३, ३.

विश्वऽभेषजः २. ४, ३; ४. १०, ३; १३, ६; १०. ३, ३; १९. ३५, ५; ३९, ५; ६; ७; ८; ९.

विश्वऽभेषजीः ८. ७, २६.

विश्वऽभेषजीम् ६. ५२, ३.

विश्वऽभेषज्या ६. १३६, ३.

विश्वऽभोजसम् ४. ३५, ३; १८. ४, ६.

विश्वम् १. १०, २; ३१, ४; ३२, ४; २. १, १; ३. ३१, ५; ४. २, ६; ११, १; ३२, १; ५. २, ८; ११, ८; ६. ४४, १; ५१, २; ५७, ३; ७७, १; ८८, १; ७. १, २; १२, १; २१, ६; ५७, २; ८. ९, ९; ९. ३, २०; ५, २१; १२, ४; १५, १९; २६; १०. ६, १७; ७, ३५; ८, ७; १३; ११. ६, २२; ९, १; २; १३. १, १; ५२; २, ३; १९; २०; ३१; ४४; ३, १५; १४. १, २२; २, ६४; १८. १, १८; ५३; ३, २४; १९. ४७, २; ५५, ६; २०. १०, २; १५, २; ६; ३०, ५; ४७, १६; १७; ५६, ६; ५९, २; ६५, ३; ८७, ६; ९५, ३; १०७, ११.

विश्वऽमानुषः २०. ४३, ३.

विश्वऽमित्राः १८. ३, ६३; ४, ५४.

विश्वम्ऽइन्वम् २०. ३५, ४.
विश्वम्ऽइन्वाः ५. १२, ५.
विश्वमिन्वे इति विश्वम्ऽइन्वे २०. ९१, ११.
विश्वम्ऽभर २. १६, ५.
विश्वम्ऽभरा १२. १, ६.
विश्वऽराधसः ७. १८, २.
विश्वऽरूपः ४. ८, ३; ९. १, ५; ४, २२; १८. १, ५.
विश्वऽरूपम् २. ३२, २; ४. १४, ९; ९. १, २; ११, ७; ८; ९; १०; ११; १२, २५; १०. ७, ८; ८, ९; ११; १३. १, ८; १४. १, ६१; २, १२; २०. ९१, १०.
विश्वऽरूपा ४. ३४, ८; ९. ५, १०; १०. १, २; १५; २४; १४. २, ३२.
विश्वऽरूपाः २. ३४, ४; ३. १०, ६; २८, १; ४. १५, २; ३; ३५, ६; ५. २३, ५; ९. १२, २६.
विश्वऽरूपाणाम् २. ३०, ४.
विश्वऽरूपान् १३. १, २२.
विश्वऽरूपाम् ६. ५९, ३; १०. १, १; १२. १, ११.
विश्वऽरूपैः १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४.
विश्वऽरूप्यम् ९. १४, ९.
विश्वऽवसुम् २. २, ४.
विश्वंवसो इति विश्वंऽवसो १४. २, ३५.
विश्ववसो इति विश्वऽवसो १४. २, ३३.
विश्वऽवारः ५. २७, ३.
विश्वऽवारम् ७. ४९, १.
विश्वऽवाराभिः २०. ३६, ११.
विश्वऽवाराम् ७. १६, १.
विश्वऽवारायाः ९. ३, १.
विश्वऽवारे ७. २१, ४; ८४, १; ९. ३, २; ४; १२. ३, ११.
विश्वऽविदः ९. १४, १०.
विश्वऽवेदसः ३. ३, १; ६. ९२, १; १९. २७, ६.
विश्वऽवेदसः ६. ९३, ३.
विश्वऽवेदसम् २०. १०१, १
विश्वऽवेदसे १. ३२, ४.
विश्वऽवेदाः ७. ९६, १; २०. १२५, ६.
विश्वऽव्यचाः ९. १२, १५; १२. ३, १९; ५३.
विश्वऽशंभुवम् १. ६, २.
विश्वऽशंभूः ६. ४७, १.
विश्वऽशारदम् ९. १३, ६; १९. ३४, १०.
विश्वऽसृजः ११. ९, ४.
विश्वस्मात् ६. ९६, २; ७. ११७, २; ८. ७, २८; १४. २, ४४; २०. १२६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३.
विश्वस्य २. ३१, १; ३. ७, ५; ११, ३; ४. २५, १; ५. २५, ७; ६. ३९, ३; ५८, ३; ८६, १; ९१, ३; ९५, ३; ८. ३, १४; ४, १६; ९. १४, २२; १५, १३; १४; ११. ६, २३; ९, १५; १६; २०. ५, ३; ३४, ९; ९६, २; ८; १३७, ५.
विश्वऽस्वम् १२. १, १७.
विश्वहं २०. ३४, १८.
विश्वहा ५. २७, ७; ९. २, १९; २०; २१; २२; २३; २४; १२. १, १७; २७; १९. ५०, २.
विश्वा १. १, १; १६, ३; २९, ३; २. १, ३; ५; ६, ५; २८, २; ३. २०, ८; ४. १, ३; १३, ४; २६, ५; ३०, ७; ८; ३२, ३;

५. ११, ४; ५; १२, ९; २८, ८; ६. १९, १; २०, ३; ३४, ४; ३६, २; ५३, २; ८०, १; ११०, २; १४२, १; ७. ११, १; १८, ३; २७, ३; ४३, २; ६२, ७; ६५, १; ८४, ४; ८५, ३; ८६, १; ९२, १; ११५, २; ९. १, ५; ४, १; १४, २; ११; १४; १०. ८, १८; ११. २, ११; ७, ९; १३. १, ११; २, ९; १०; ११; १२; ३२; ३४; ३८; ३, ३; १४; १८; १४. १, २३; २, ३०; १७. १, १६; १९. ६, ३; ५३, १; २; ३; ६; २०. २७, ६; ३१, ३; ३४, ४; ५५, १; ५८, १; ७३, १; ७७, ५; ८०, २; ८१, २; ८५, ३; ९२, २१; ९३, ८; ९४, १; १०७, १३; ११८, ४.

विश्वाः २. ६, १; ५. ७, ९; २३, २; ६. २२, ३; ९७, १; ७. ७७, ९; ८९, १; ८. ४, ११; १०. ५, ३६; ८, ३६; १३. १, २२; २, २८; ३३; १६. ९, १; १८. २, ५९; २०. १७, १; २९, ३; ३६, ९; ३७, १; ४३, १; ४६, २; ५४, १; ६५, १; ९१, ११; ९२, ११; ९३, ८; ९५, ४; १०५, १; २; १०७, १; ११०, २.

विश्वान् ३. ८, ३; २१, ८; ५. २२, २; ७. ३९, ३; ११. ८, ५; १९.

विश्वानरे ४. ११, ७.

विश्वानि १. ६, २; ४. ३९, १०; ६. ४५, २; ६३, ४; ७. ४२, १; ८. ३, २४; १०. ५, ६; १५. ३, १०; ११; १९. ४९, २; २०. १२, १; ३६, ७; ४४, २; ६९, ७; ७१, ८; ७७, ६.

विश्वाभिः ११. ८, १९; २०. १९, ३; २५, ७; ३३, २; ३७, ३; ११८, १.

विश्वाम् २०. १७, १०; ९४, १०.

विश्वामित्र १८. ३, १६.

विश्वामित्रः १८. ३, १५.

विश्वामित्रम् ४. २९, ५.

विश्वाय १३. २, १६; २०. ४७, १२.

विश्वाषाट् १२. १, ५४; १३. १, २८.

विश्वासाम् २०. ९२, १६; १०५, ४.

विश्वासु ५. ११, ८; ९; १९. ४९, ५; २०. १०४, ३.

विश्वाहा ३. १५, ८; ७. ५२, १; ७८, ४ १८. ३, ५१; ४, ३४; २०. ८७, १.

विश्वे १. ९, १; १३, ४; ३०, १; ३५, ४; २. ९, ४; १२, ५; १३, ४; ५; २८, ५; २९, ५; ३. ३, ५; ४, ४; ८, ४; १९, ५; २२, १; ४. २, १; ५; ८, ३; ५. २, १; ३, ४; ६; २७, ७; १२; ६. ४७, २; ६१, १; ९३, ३; १११, ४; ११२, १; ११५, १; ३; १३२, २; ७. ६, १; १७, १; १८, ३; २२, १; २५, १; ३६, १; ५२, ७; ७७, ३; ८. १, ७; २, २१; ५, १९; ८, १३; ९. २, ७; ४, १८; १०, २; १४, २१; १५, १८; १०. ५, ५०; ११. १, ३३; ७, २४; ८, १८; १२. १, ५३; १३. ३, २४; १४. १, १५; ३२; २, ५३; ५४; ५५; ५६; ५७; ५८; १५. २, २; १८. १, ३२; ५२; ३, ११; ३९; १९. ९, १२; १४; २०, ४; ३०, २; २०. ३४, ७; ६३, १; ८९, १०; ९२, ८; १०७, ४; १२४, ४.

विश्वे ६. ११४, ३.

विश्वेन २. १६, ५; १७. १, २४.

विश्वेभिः ४. ९, १; ५. २९, २; ३; ७. ११०, १; २०. ६, ३; ६०, २; ७१, ७.

विश्वेभ्यः १५. २, ३.

विश्वेषाम् ४. १, ७; १५. २, ४.

विश्वेषु ६. ९८, २; २०. ७२, १.
विश्वैः २. १६, ४; ३. १७, ९; १२. ३, १०; १८. ३, २८; १९. १७, १०; ४०, १.
विषं ४. ६, ३.
विषः ५. १७, ९.
विषऽगिरिः ४. ६, ७.
विषऽदूषणम् ६. १००, १; १०. ४, २४.
विषऽदूषणीः ८. ७, १०.
विषऽधानः २. ३२, ६.
विषम् ४. ६, १; ४; ५^{२}; ६; ८; ७, १; २; ५. १३, १^{२}; २; ४^{२}; ८; ९; १०; ११; १९, १०; ६. १२, १; २; १००, २; ३; ७. ५८, १; ३; ५; ७; ८; ९३, १^{२}; ८. ३, १६; १४, १५; १६; १९, ३; ४; ९. १३, १०; ११; १२; १९; २०; १०. ४, ३; ४; १९; २०; २१; २२^{२}; २६^{४}; १२. ४, ३९; ८, ४.
विषऽवत् १४. १, २९.
विषऽवति ८. १४, १३.
विषस्य ४. ६, २; ५. १८, ४; १०. ४, २५.
विषा ७. ११८, २.
विषाणि ६. ९०, २.
विषातकी ७. ११८, २.
विषुणे २०. १३७, ८.
विषुऽरूपम् १९. ५, १.
विषुऽरूपा १८. १, २; ३४.
विषुऽवतः २०. १०९, १.
विषुऽवता ९. १५, २५.
विषुऽवति ९. ३, ८.
विषुऽवन्तम् ११. ९, १५.
विषुऽवृत् २०. १७, ३.
विषुऽवृतः १०. २, ११.
विषूचः ३. १, ५; २, ३.
विषूची १. २७, २.
विषूचीः १. १९, १; ९. २, २१; १५, ११; १९. ८, ६; १५, २.
विषूचीनम् ३. ७, १.
विषूचीना ९. १५, १६.
विषूचीनान् ८. ६, १०.
विषूचीम् ६. ९०, १; ७. ४३, १; २०. २९, ५.
विषे ५. १३, ५; ७. ९३, १; १०. ४, २६.
विषेण ५. १३, ४; ८. ३, २३; ११. २, २६.
विष्टः १९. ४९, ८.
विष्टपम् ११. १, ७; ५, १; २०. ९२, ४.
विष्टपि १०. १०, ३१; ११. ५, २; १३. १, १६; १८. ४, ४.
विष्टम्भाः १३. ४, १०.
विष्टारिणम् ४. ३४, ३; ४; ५; ८.
विष्टारी ४. ३४, १.
विष्णवि २०. ९९, २; १११, १.
विष्णवे १२. ३, ५९.
विष्णुः ३. २७, ५; ५. ३, ३; २५, ५; २६, ७; ६. ३, १; ७. १८, ४; २७, २; ४; ५; ८. ५, १०; १०. १०, ३०; १२. १, १०; १३. २, ३१; १५. १४, ९; १८. ३, ११; १९. ९, ६; १०, ९; २०. ३५, ७; १०६, ३.
विष्णुःऽइव १४. २, १५.
विष्णुना २०. ९५, १.
विष्णुम् ३. २०, ४; ७; ७. २६, १; २; ११. ८, २.
विष्णो इति ७. २७, ३; ८^{२}; ४५, १; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४.
विष्णोः ७. २७, १; ६; ७; ४८, ३; ९. २,

६; १५, १७; १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; १८. १, ४५; २०. १४१, २.
विष्वक् १. २७, २; ३. १, ४; ६, ६.
विष्वङ् ११. १०, ३३; १९. ६, २; ४९, ८.
विष्वञ्चः १. १९, २; १९. ३८, २.
विष्वञ्चम् २. ३३, ७; २०. ९६, २३.
विऽसक्तम् १२. ३, १३.
विऽसर्गे ५. १, ६.
विऽसल्पकः ६. १२७, ३; १९. ४४, २.
विऽसल्पकम् ६. १२७, ३; ९. १३, २; ५.
विऽसल्पकस्य ६. १२७, १.
विऽसल्पस्य ९. १३, २०.
विऽससहिः १. २९, ६; १२. १, ५४; १९. ३३, ४.
विऽससहिम् १७. १, १; २; ३; ४; ५.
विऽससहौ १९. २३, २७.
विऽसानका ६. ४४, ३.
विऽसानया ३. ७, १.
विऽसाना ६. १२१, १.
विऽसाने ३. ७, २.
विऽसितम् १. ३, ८.
विसितऽस्तुपः ६. ६०, १.
विऽसिताः ४. १६, ६.
विऽसिते ४. १, ६.
विऽसृज्यमानायै ६. ९०, ३.
विऽसृष्टाः २. ३, ६; ४. १५, १६.
विस्कन्धऽदूषणम् २. ४, १; ३. ९, ६; १९. ३५, १.
विऽस्कन्धम् १. १६, ३; २. ४, ३; ४; ३. ९, २; ४. ९, ५; १९. ३४, ५.
विऽस्कन्धात् २. ४, २; ५.
विऽस्कन्धानि ३. ९, ६.
विऽस्तभितः ११. २, २३.
विस्तभिते इति विऽस्तभिते १०. ८, २.
विऽस्तभ्नाति १३. १, २५.
विऽस्था ७. ३, १; १२. १, ५.
विऽस्थाः ४. १, १; ५. १, ८; ६, १; १८. ४, ४.
विऽस्थितम् ६. १७, ४; १२६, १.
विऽस्थिता ३. ९, ६.
विऽस्थिताः ६. ९०, २.
विस्थिताःऽइव ७. १२०, ४.
विऽस्रसः १९. ३४, ३.
विऽस्रस्तम् ४. १२, ३.
विऽहत्यै ७. ७७, ९.
विऽहरति २०. ९६, १४.
विऽहरन्ते ८. ४, ९.
विऽहवे ५. ३, ३; ११.
विऽहवेषु ५. ३, १.
विऽहव्यः २. ६, ४.
विऽहव्येन ७. ५, ४.
विहल्हः ६. १६, २.
विऽहाय ३. २८, ५; ६. १२०, ३.
विऽहायाः १७. १, २७.
विऽहितः १८. ४, ११.
विऽहितस्य १८. ४, ८.
विऽहिता १०. २, २४; २५; ११. १, २३.
विऽहिताः १२. १, ३६.
विऽहितानि ९. १४, १६.
विहिते इति विऽहिते १२. २, ५२.
विऽहृतम् ५. २९, ५.
विऽहृदयम् ५. २१, १.
विऽह्रुतम् १४. २, ४७.
विऽह्रुतस्य ७. ५८, २.
विह्वयेते इति विऽह्वयेते २०. ३४, ८.

वीच्या १८. १, ७.
वीडयस्व ६. १२५, १; १२६, २.
वीडुऽअङ्गः ६. १२५, १.
वीडुः १. २, २.
वीडुऽहराः ५. १७, १.
वीतऽपृष्ठाः ६. ६२, २.
वीतम् ७. ७७, ५.
वीतये २०. ६९, ३.
वीतऽहव्यः ६. १३७, १.
वीतऽहव्यम् २०. ३७, ३.
वीतात् १८. १, २६.
वीथः ७. ३०, २.
वीध्रे ४. २०, ७; ९. १, २४.
वीयन्ते ११. ६, ३.
वीर ११. १, १०; २०. ४५, २; ५६, २.
वीरः ३. ५, ८; २३, २; ५. १९, ४; ६. ११०, ३; ८. ५, १; २; १३. २, ९; १४. २, ८; १९. ३१, १४; २०. ६४, ४.
वीरऽघ्नी ६. १३३, २.
वीरऽतमा ७. २६, १.
वीरऽपोषम् १३. १, १२.
वीरम् ६. ९७, ३; ७. ४९, १; ५०, १; १९. १३, ६; २०. ३५, ५; १०८, १.
वीरयध्वम् १२. २, २६.
वीरयस्व ५. २५, ८.
वीरऽयुः २०. ६०, १.
वीरऽवत् २०. १२, ६.
वीरऽवतीः ३. १६, ७.
वीरऽवन्तः २०. ८८, ६.
वीरऽवित् ११. १, १५.
वीरऽशुष्मया २०. २१, ५.
वीरऽसूः १४. २, १७; १८.
वीराः २. २६, ४; ५; ५. १७, ७; ९. ५, २; १५, २५; १२. २, २१; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; १८. १, २; ३, ६१; १९. १३, ११; २०. ९१, २.
वीराणाम् १. २९, ६; ३. १९, ६.
वीरान् ४. ७, ७; ५. ६, २; ६. ९३, १; १९. ३६, ४.
वीराय ८. ५, १; १९. ३१, १४.
वीरिणी २०. १२६, ९; १०.
वीरुत् १. ३४, १; २. ७, १; ८, २; ३; ४; ५; ६. ३२, २; ७. ५८, १; २.
वीरुत्ऽभिः ५. २८, ५; ८. ७, १५.
वीरुत्ऽभ्यः १९. ३५, ४.
वीरुधः १. ३२, १; २. ९, ३; ४; ३. २७, ५; ४. १५, ३; ७. ९२, १; ८. ७, ४; ११; १८; ८, १४; १०. १, १२; १०, २१; ११. ६, १७; ८, १; ९, २१; ११, २४; १२. ३, ३१; १५. ६, २.
वीरुधम् ६. ५२, ३; ८. ७, २३.
वीरुधा ६. १३६, ३.
वीरुधानाम् ६. २१, २.
वीरुधाम् ३. १८, १; २३, ६; ४. ३७, ६; ५. ४, १; २४, ७; ६. १३८, १; ८. ७, २; १२; १४; २०; ११. ८, १५; १५. ६, ३; १९. ३३, १.
वीरुधाम् ४. १९, ८.
वीरेण ३. ५, ८.
वीरेभिः २०. १६, १२.
वीरेषु १२. १, २५; २, १५.
वीरैः ८. ४, १५.
वीर्यम् १. ७, ५; ३. १९, १; २; ४. २४, ६; ५. ८, २; ८. ७, ५; ९. ४, २३;

१०. २, ५; ५, १; २; ३; ४; ५; ६; ११. ९, १७; १२. ५, ६; १९. ३४, ८; २०. १५, ५[२]; १७, ५; ७३, २.

वीर्यऽवता ४. ३७, ११; १०. १, १४.

वीर्यऽवति ६. १३९, ५.

वीर्यऽवती ४. ३७, ६.

वीर्यवत्ऽतरः १८. ४, ३८.

वीर्यऽवान् ८. ५, १; १४. १, ३७.

वीर्यस्य २०. ७५, २; ३.

वीर्या २०. ६५, ३.

वीर्याणि १. ३५, ३; २. ५, ५; ५. २६, ११; ७. २७, १; २; ११. ११, १; १२. ३, २; १३. २, ३२; १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २४; १९. २२, २१; २३, ३०; २७, १०[२]; ३०, २; ३३, ५; ३७, १; ४६, ५.

वीर्याय १०. ६, ७; ११. १, ३; ७; २, १४; १९. ३७, २; ४६, १; २०. ३५, १४.

वीर्येण ५. २८, ४; ९. २, १; १०. १, १२; १९. १९, ९; ७२, १; २०. ३३, ३.

वीर्यैः ७. २६, १; १९. ३०, १.

वीलिता २०. ३६, ६.

वीलु २०. ७०, १.

वीलौ २०. ४३, २.

वीहि ६. ८३, ४; २०. २३, ३.

वीहि १९. ५२, ५; २०. ६७, ५.

वृकः ४. ३, १; २; ७. ५२, ५; १२. ४, ७; १९. ४७, ६; २०. ९७, २.

वृकःऽइव ५. ८, ४; ६. ३७, १.

वृकम् ४. ३, ४; १२. १, ४९.

वृकस्य १९. ४७, ८; ५०, १.

वृकाः १२. १०, ३.

वृकात् ५. २१, ५.

वृकौऽइव ७. १००, २.

वृक्कौ ७. १०१, १; ९. १२, १३.

वृक्णम् ८. १२, २.

वृक्तऽबर्हिषः २०. ५२, १; ५५, २; ५७, १४; ९२, १५.

वृक्तऽबर्हिषे २०. १०१, ३.

वृक्षः १८. २, २५.

वृक्षःऽइव ४. ७, ५; ७. ६१, १.

वृक्षम् १. २, ३; २. १२, ३; ६. २, २; ८, १; ७. ५२, १; १२०, २; ९. १४, २०; १८. १, १५; १६; २०. १७, ४.

वृक्षम्ऽइव ६. ३७, २; ७. ११४, ४.

वृक्षम्ऽवृक्षम् ५. ५, ३.

वृक्षऽसर्प्यैः ९. २, २२.

वृक्षस्य ३. ६, ८; ४. ६, ६; १०. ७, ३८.

वृक्षाः ५. १९, ९; ६. १५, १; ४४, १; १०. ३, १५; ८, ३१; १२. १, २७.

वृक्षाणाम्ऽइव ६. १५, २; ३.

वृक्षात् ६. १२४, २; २०. १६, ८.

वृक्षात्ऽइव १. १४, १; ८. ६, २६.

वृक्षान् ५. ५, ९; ६. ४५, १; १२९, २; १०. १, १७; ३, १३; १४; १२. १, ५१.

वृक्षि ६. ३०, २.

वृक्षे ९. १४, २१.

वृक्षेषु ६. १२९, ३; ७. ६८, १.

वृङ्क्ष्व ३. १२, ६.

वृङ्ग्धि १. २५, १; २; ३; ५. २२, १०; ६. ३७, २; ९. २, ५; १६; ११. २, २०.

वृजनाः २०. ७९, २.

वृजनीभिः ७. ५२, ७; २०. ८९, १०.

वृजनीषु ९. १४, ९.

वृजनेन २०. ११, ६; १७, १०; ९४, १०.
वृजिनम् १. १०, ३; ८. ३, १४; ४, १३; ११. १०, २०.
वृजिना १. २०, १; ५. ३, ६; ७. ५८, ४.
वृजिनान् २०. ११, ६.
वृजिनानि २. १२, ६.
वृज्यते २०. २५, ६.
वृज्यते ५. १२, ४.
वृञ्जन्तु ६. ९३, १.
वृञ्जाते इति १०. ७, ४२.
वृणक्तु १. ३०, ३; ४. २१, ७; ६. २७, २; ७. ७९, १; ८. २, ९; ९. २, ५; १६; ११. २, ८[२].
वृणताम् ३. ४, २.
वृणते १८. १, २१.
वृणते २. ६, ३.
वृणानः २. १३, १; ७. ११०, १.
वृणाना १२. १, ३७; १८. ३, १.
वृणानाः १२. २, २४.
वृणीमहे २०. २७, ६; १०१, १; १०३, २; १०४, ४.
वृणीषे ९. २, २५.
वृणीषे ११. १, १०.
वृणीष्व २०. ३७, ९.
वृणे ७. १६, १; १०. ४, २१; २०. २०, २; ५७, ५.
वृण्वते २०. ६९, २.
वृतः २०. ८७, ४.
वृतः ८. ६, ३.
वृतम् ७. ५२, ४.
वृता १२. १, ५२; २०. १२४, १.
वृत्रः ६. ८५, ३.
वृत्रऽघ्नः ४. २४, १; ६. ८२, १.
वृत्रऽघ्ना ३. ६, २.
वृत्रम् २. ५, ३; ८. ५, ३; १२. १, ३७; २०. ११, ३; ३५, १०; ३७, ९; ७७, ७; ८९, ५; १०५, २; १३९, ४.
वृत्रस्य १. २१, ३; २०. ३५, ६; १०७, ३.
वृत्रस्यऽइव ६. १३४, १; १३५, १.
वृत्रऽहत्ये २०. ३७, १०.
वृत्रऽहत्येन १८. १, ३८.
वृत्रऽहत्येषु २०. २१, ६; ३७, ३.
वृत्रऽहन् १. २१, ३; ३. १, ३; ५. ८, ७; ९; ६. ९८, ३; ११. ११, २३; २०. ५, ३; ६, ८; १८, ६; २३, ४; ५२, १; ५७, १४; ११२, १; ११६, २.
वृत्रऽहना ४. २८, ३; ७. ११५, २.
वृत्रहन्ऽतमा ७. ११५, १.
वृत्रऽहा १. २१, १; ४. ३२, ३; ५. २५, ६; ६. ७५, २; ७. ८१, २; ८. ५, २२; १०. १०, १०; ११. १२, २७; १८. १, ३८; १९. १५, ३; २६, ४; २७, २; २०. ७, २; १२, ७; ५६, १; ९२, १६; ९३, ६; ९५, २; ९७, ३; १०४, ३; १०५, ४.
वृत्रा २०. ३६, १०; ३७, ४; ७०, १८.
वृत्राणाम् २०. ६८, ८.
वृत्राणि ४. ३२, ७; ५. ६, ४; ७. ९८, १; ११५, १; २०. ५, २; ३; ११, ११; १२, ३; २१, ६; ४१, १; ५१, २; ६१, ६; ६२, १०; ९०, २; ११७, २.
वृत्रात् ४. १०, ५.
वृत्राय २०. १९, ५; ६; ३५, १२; ४७, १; १३७, १२.
वृत्रे ३. २१, १.
वृत्रेषु २०. ७०, ११; ९८, १.
वृत्वा १९. ६, १.

वृद्धः २०. ६९, ४.
वृद्धऽवृ॑ष्णः ७. ६४, १.
वृद्धासु॑ ११. १०, ३४.
वृधः २०. ५६, २; ६४, २; ३; १११, ३.
वृधाम ५. १, ९.
वृधि २०. ७०, १२.
वृधे ११. २, २४; १८. ३, २३; २०. ५४, २; ९४, ४.
वृन्ता॑त् ८. ६, २२.
वृश्च १२. ११, १; १९. २८, ७[४].
वृश्च ७. ९५, १; ८. ३, १०; १५; १२. ११, १[२].
वृश्चत् २०. ३५, १०.
वृश्चाति १२. ९, ४.
वृश्चतु १. ७, ७.
वृश्चते॑ ६. १३६, ३; ८. १२, २.
वृश्चते १२. ४, ६; १२; २६; ३४; १५. २, ३; ११; १७; २३; १०, २[२]; १२, ६; १०.
वृश्चन्ताम् ८. ३, १६.
वृश्चन्ति ७. ५८, ७; १२. ४, २८.
वृश्चन्ते १२. २, ५०; ४, ५१.
वृश्चामि॑ २. १२, ३; ३. १९, २; ६. ६५, २.
वृश्चामि २. १२, ७; २५, २; ३२, २; ५. २३, ९; १०. ६, १; १३. १, ५६; ५७.
वृश्चि॑कः १२. १, ४६.
वृश्चि॑कम् १०. ४, ९.
वृश्चि॑कस्य १०. ४, १५.
वृष॑णः ११. २, २२; २०. १०२, ३.
वृषणः ११. १, २; २०. १३७, ८.
वृष॑णम् २०. १२, ६; ६१, १; ७२, २; ७५, १; ८५, १; ९१, ९; १०; १०२, ३; १२५, ३.
वृष॑णा ७. ११५, २; २०. ३७, ६.
वृषणा ७. ६०, २; ७७, १; २; ८. ४, १.
वृषण्यतः ६. ७०, १; २; ३.
वृषण्यन्ती॑ऽइव ५. ५, ३.
वृषण्यन्त्या॑ः ६. ९, १.
वृषण्वसू इति॑ वृषण्ऽवसू २०. १३, १.
वृषऽत्वना २०. ६१, ५; ६२, ९.
वृष॑ऽदतीम् १. १८, ४.
वृषन् ६. ६३, ४; २०. १८, ४; ३२, ३; ३६, ८; ७०, १२; ७५, ३; ८१, २; ९२, २१; ९३, ५; १०२, ३.
वृष॑ऽपत्नीः २०. ६१, ३.
वृषभ ७. ८९, २; २०. २२, १.
वृषभः ४. ५, १; २४, ३; ६. ९८, ३; १०. ५, १८; ११. १, ३५; १३. १, १२; २५; ३३; १६. १, १; १८. ३, ६५; १९. १३, २; २०. १२, ७; ३४, १३; ३६, १; ३७, १; ४७, १; ९०, १; १२६, १५; १३७, १२; १४३, ९.
वृषभम् ७. ४०, १; ८५, २; १९. ४२, ४; २०. १, १; ६, १; ७, १; ७१, १०; ८५, २; ९४, ३; ११३, २.
वृषभस्य॑ १२. २, ४१; २०. १७, ३.
वृषभाः ९. १, ९.
वृषभाय॑ ६. ३४, १; १२. १, ३७; १८. १, ११; २०. ८७, १.
वृष॑ऽभिः २०. २४, ७; ९१, ७.
वृषभौ १९. १३, १.
वृष॑ऽमन्यवः २०. ७२, १.
वृषऽयमा॑नः २. ५, ७.
वृषऽयसे २०. ९४, ४.
वृषऽयस्व ६. १०१, १.
वृषऽसवास॑ः २०. ८९, ८.
वृषस्व ७. ८१, २; २०. ६, २; ७, ४; ८, २; ३२, ३.

वृषा॑ १. १२, १; २१, १; २९, ६; ३. ७, २; ४. ४, २; ३६, १; ५. १३, ३; १९, ४; २०, २; २५, ८; ६. ४८, ३; ६७, ३; ८६, १[४]; ८. ५, १२; २२; ९. १, १०; २०; १०. ३, १; ११. ९, १६; १४. १, ४३; १८. १, १८; ४, ५८; १९. २७, १; ३१, २; ११; २०. १७, ६; ८; ४७, १; ७०, १४; ७२, ३; ७७, ३; ९३, ५; १०२, १; १३७, १२.
वृषा॑ऽइव ५. २०, ३.
वृषा॑कपायि २०. १२६, १३.
वृषाक॑पिः २०. १२६, १; ३; १८.
वृषाक॑पिम् २०. १२६, ४; ८.
वृषाकपे २०. १२६, २०; २१; २२.
वृषाक॑पेः २०. १२६, २; १२.
वृषा॑णौ १९. १३, १.
वृषेथाम् ७. ६०, २.
वृषो इति॑ २०. १०२, २.
वृष्टिः ६. २२, ३; २०. १७, ७; ७३, ५.
वृष्टिःऽई॑व ६. ५४, १.
वृष्टिमान्ऽई॑व २०. १३८, १.
वृष्टे ३. २४, ३.
वृष्ट्वा १. १२, १; ३. ३१, ११; ५. २४, ५; ७. ४०, १.
वृष्ट्वा ८. ३, २.
वृष्ण॑ः ४. ८, ३; १५, ११; ७. ६०, २; ९. १५, १३; १४; १९. १३, १०; २०. ९४, ८.
वृष्णा॑ १९. १३, ३; २०. १०९, १.
वृष्णि॑ २०. ९, ४; ४९, ७.
वृष्णिना॑ २०. १०७, ३.
वृष्णे॑ १२. १, ३७; १८. १, १८; २०. २५, ७; ३३, २; ३७, ६; ८८, ६.
वृष्ण्य॑म् ४. ४, ४; ५; ५. ४, १०; ६. ८९, १; १३८, ४; २०. ९९, २; ११९, २.
वृष्ण्यऽवन् ५. २५, ८.
वृष्ण्य॑ऽवान् २०. ३६, १.
वृष्ण्या॑ ७. ५२, ४; २०. २१, ६; ८१, २; ९२, २१.
वृष्ण्या॑नि २०. ९४, २.
वृष्ण्ये॑न २०. ९४, १.
वृह १२. ११, ८; १८. १, ९.
वृहतम् ७. ४३, १.
वृहामः ६. १२७, ३.
वृहामसि २. ३३, ३; ७; ६. ९०, १; २०. ९६, १९; २३.
वृहामि २. ३३, १; २; ४; ५; ६; २०. ९६, १७; १८; २०; २१; २२.
वृहेव १८. १, ८.
वेः ९. १४, ५.
वेग॑ः १२. १, १८.
वेगा॑सः ४. १५, ३.
वेणोः १. २७, ३.
वेतसम् १०. ७, ४१; १८. ३, ५.
वेति २०. १७, २; ७३, ५.
वेत्त॑वे २. ३६, ७.
वेत्तु १२. ३, १२.
वेत्थ॑ १. ८, ४; ५. ११, ५; ३०, १४; १२. ४, ४३; २०. ६६, ३.
वेत्थ ४. ९, ३; ५. ११, ४; ६. ११७, १; १३. १, ३९; १८. २, ३५.
वेद॑ २. १, २; २६, १; ३. ७, ६; २४, २; ४. ११, ९; ११; ५. ७, ७; ११, १०; २५, ६[२]; ३०, १२; ६. ७६, ३; १२७, २; ८. ७, १८; १०, ३; ५; ७; ९; ११; १३; ११, १०; १२, २; ४; ६; ८; १३, ४;

८; १२; १६; १४, ४; ८; १२; १६; १५, ४; ९. १, २२; २३; २४; ५, ३१; ३२; ३३; ३४; ३५; ३६; १०, ३; ५; ७; १०; ११, १४; १२, २६; १४, ५; १८; २१; १५, १८; १०. २, २८; २९; ३०; ७, १७[२]; ४१; ८, ३८; १०, ३; ११. ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ५, २; ६, १८; ८, २३; १२. ४, १८; १३. १, ४४; ५, २; ३; ४; ५; ६; ७; ८; ६, १; ३; १४. १, २९; १५. २, ८; १४; २०; २८; ३, ११; ४, ३; ६; ९; १२; १५; १८; ५, ३; १६; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ७, ३; ५; ८, ३; ९, ३; १०, ९; ११; ११, ७; ९; ११; १३, १४; १४, २; ४; ६; ८; १०; १२; १४; १६; १८; २०; २२; २४; १८. १, ५; १९. २६, १; ४[३]; ४८, ६.

वेद २. १, ३; ४. १६, २; ६. ८४, १; ११९, २; ७. १, २; १०, २; ८. ७, २३[२]; ९, १०; ११, २; ९. १, ६; ७; १५, १०; १०. ७, २३; २९; ३०; ८, ३८; १०, ३[२]; ११. १२, २; १८. १, ७; १८; ३३; ४, ४१; १९. ३९, ९; ४८, ६; २०. ५३, १; ५७, ११.

वेदः ४. ३१, २; ५. २०, ४; १०; ७. ५७, १; १५. ३, ७; २०. ३७, १; ५६, ६[२].

वेदः ७. २९, १.

वेदत् १४. १, ५७.

वेदति २०. ४३, ३.

वेदनम् ६. ११, १; २.

वेदम् १०. ८, १७; १९. ६८, १; ७२, १.

वेदऽमाता १९. ७१, १.

वेदयामि ६. ११९, २; १२. ३, ४४.

वेदांसि ६. ६६, ३.

वेदाः ४. ३५, ६.

वेदाः १९. ९, १२.

वेदिं २०. ७७, ४.

वेदिः ५. २२, १; ७. २९, १; ९. १५, १४; १०. ९, २; ११. १, २३; १३. १, ४६; ५३; १९. १०, ७; ४२, २.

वेदिता १०. ७, २४.

वेदिम् ७. १०४, १; ११. १, २१; १२. १, १३; १३. १, ५२.

वेदीयान् २०. ८७, १.

वेद्याम् ११. १, २४; १२. ३, २३; १९. ३३, ३.

वेद्याय १९. ३, ४.

वेधः २०. ३६, ११.

वेधसः १. ३२, २; ३. ९, ३; ५. १८, १४; ७. ७७, २; १२. १, ३९; २०. ७२, ३.

वेधसा १९. ३१, १.

वेधसाम् ५. २८, ६.

वेधसे ३. २१, ६; २०. १, ३.

वेधाः १. ११, १; ५. २०, ४; १८. १, १; २०. ७७, २; १२६, १०.

वेनः २. १, १; ४. १, १; ५. ६, १; १६. ३, २; २०. २५, ५.

वेनः ४. ८, २.

वेनन्तः १८. ३, ६६.

वेनस्य २०. ३५, १४.

वेपते १८. १, २३.

वेपथुः १२. १, १८.

वेपय ११. ११, १२; १८; १३. ३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३;

१४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५.
वेपर्यन्तम् २०. ६३, ८.
वेर्पा २०. ३६, ९.
वेप्यमाना १९. ९, ८.
वेविषत् ५. १७, ९.
वेविष्यात् १५. १३, १३.
वेवेष्टु २. १२, ८.
वेवेष्मि १५. १३, १३.
वेशन्ताः ११. ८, १०.
वेशन्त्याःऽइव १. ३, ७.
वेशय २. २५, ४; ९. २, २५; १३. १, २.
वेशयन्तु १८. २, २६.
वेशयामसि ६. १०८, ३.
वेशयामहे ६. १०८, ५.
वेशयामि ३. १३, ७.
वेशयामि ७. ९५, ३; १२. ३, २२; १८. ४, ४८.
वेशयेत् ९. ५, २३.
वेशसः २. ३२, ५; ५. २३, १२.
वेश्मनि ५. १७, १३; ९. ७, १३.
वेष्टताम् ६. १०२, २.
वेष्टय १२. ११, ७.
वेष्टयामि १०. ५, ३६; १६. ८, ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३३.
वेहत् ३. २३, १.
वेहतम् १२. ४, ३७; ३८.
वै ३. ७, ५; ४. ११, ११[२]; १९, ६; ५. ५, १; ३; ६; १७, ६; १०; १८, ४; १४; १९, ५; ८; १२; १३; १४; २२, ८; ६. ११, १; २[२]; ४४, ३; ४९, २; ५७, १; ९१, ३; ७. १३, २; ८१, १; ८६, ३; ९३, १[२]; ८. २, २४; २५; ४, १३; ५, १६; १०, १; ९. १, २२; २, २४; ५, २०; २१; ३१[२]; ३२[२]; ३३[२]; ३४[२]; ३५[२]; ३६[२]; ६, ३; ७, १; ६; ८; ९; १०; ११; १२; ८, १; २; ३; ४; ५; ६; ७; ९; ११, ५; १२, २५; १०. १, २९; २, २७; २९; ३०; ३२; ४, १५; २४; ७, २४; २७; ४१; ८, २०; ३१; ४३; १०, ३१; ११. ४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२]; ५, १; ३; ६, ५; ६; ८, ११; १०, ३[२]; ४; ७; १९; २१; २२; २३; ३२; १२. २, ५१; ४, ४७; ४९; ७, ६; १०, १; ३; ४; १३. ७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १५. २, ३; ४; ११; १२; १७; १८; २३; २४; ६, ३; ६; ९; १२; १५; १८; २१; २३; २६; ८, ३; ९, ३; १०, ३; ४[२]; ५; ६; ७; १७, ८; १८. १, १४; २, ५०; ५१; ४, ३२; ६०; १९. १४, १; ४८, ६[२]; ५३, ३; ४.
वैकङ्कतेन ५. ८, १.
वैतऽहव्याः ५. १८, १०; १९, १.
वैतऽहव्यान् ५. १८, ११.
वैन्यः २०. १४०, ५.
वैन्य[ः] ८. १३, ११.
वैबाधऽदोधतः ३. ६, २.
वैबाधऽप्रनुत्तानाम् ३. ६, ७.
वैमनस्यम् ५. २१, १.
वैयश्व २०. ६६, २.
वैयाघ्रः ८. ७, १४.
वैयाघ्रे ४. ८, ४.
वैरम् १०. १, १९; १२. ८, १.

वैराजम् १५. २, १६; ४, ८; ९.
वैराजस्य १५. २, १८.
वैराजाः ३. २६, ३.
वैराजाय १५. २, १७.
वैरूपम् १५. २, १६; ४, ८; ९.
वैरूपस्य १५. २, १८.
वैरूपाय १५. २, १७.
वैरूपैः १८. १, ५९.
वैवस्वतः ६. ११६, २; ८. १३, १०.
वैवस्वतम् १८. १, ४९; ३, १३.
वैवस्वते ६. ११६, १.
वैवस्वतेन ८. २, ११.
वैशालेयः ८. १४, १४.
वैश्यः ५. १७, ९; १९. ६, ६.
वैश्रवणः ८. १४, १०.
वैश्वऽकर्मणाः १३. १, १८.
वैश्वऽदेवः ९. १२, २४.
वैश्वऽदेवी ७. २८, १; १२. १०, ७.
वैश्वऽदेवीः ८. ७, ४.
वैश्वऽदेवीम् १२. २, २८.
वैश्वानर २. १६, ४; ३. १५, ७.
वैश्वानरः ३. २१, ३; ४. ३६, १; ६. ३५, १; २; ३; ४७, १; ५३, २; ६२, १; ११९, १; ३; ८. १, ११; ५, १०; १०. ७, १८; १२. ७, ७; १३. ३, ५.
वैश्वानरऽज्येष्ठेभ्यः ३. २१, ६.
वैश्वानरम् ४. २३, ४; ६. ३६, १; १२. १, ६.
वैश्वानरस्य ४. ३६, २; ६. ७१, ३; ८. ९, ६; १०. ५, ४३; १६. ७, ३.
वैश्वानरात् १. १०, ४; ८. २, २७; ७, १६.
वैश्वानराय ६. ११९, २.
वैश्वानरीम् ६. ६२, २; ३.
वैश्वानरे ४. ११, ७; १८. ४, ३५.
वैश्वानरेण ६. ८५, ३; ७. ११३, २.
वैष्टपान् १९. २७, ४.
वोचः ७. २, १; ५, ५; ८३, २; २०. ३६, ४.
वोचत् ७. ७७, ७; ९. १४, १८; १५, ४; १८. १, ७; ३६.
वोचत ६. ७, २; २०. ६५, २; ११९, १.
वोचति १८. १, १९.
वोचन् ५. ११, ७; ८.
वोचम् २. ५, ५; ७. २७, १; २०. ८७, ५.
वोचेत् २. १, २.
वोचेयम् १३. १, १४; ३७.
वोचेयुः २०. ६८, ६.
वोढवे १८. २, ५६.
व्यचः ४. १९, ६; ६. ६१, १; ८. ११, ७; ९; ९. ३, १५; १०. २, २४; २५; १२. १, ५३; १३. ९, २.
व्यचसः १९. ६८, १.
व्यचसा ११. ४, ८[2].
व्यचस्वतीः ५. १२, ५.
व्यतीन् २०. ९२, १०.
व्यथन्ताम् ४. ४०, १; २; ३; ४; ५; ६; ७; ८.
व्यथमानाम् २०. ३४, २.
व्यथय १३. १, ३१.
व्यथयीः ५. ७, २.
व्यथि॑ः २०. १२६, २.
व्यथिः ४. २१, ३; ६. ३३, २.
व्यथिष्ठाः १२. ३, २३; १४. १, ४८; १९. ३३, ५.
व्यथिष्महि १२. १, २८.
व्यन्तु॑ ७. ५१, २; २०. ३७, ६.
व्यन्तु ७. ५१, २.
व्ययन्तु ७. १८, ३; १४. १, ४५.
व्ययस्व १८. २, ५८.

व्ययामसि १. २७, १; ६. १०६, ३.
व्यये ६. ९१, १.
व्यश्वऽवत् २०. ६६, १.
व्यस्तऽकेश्यः ८. १, १९.
व्याघ्र ४. ३, ३.
व्याघ्रः ४. ३, १; ८, ४; ३६, ६; ८. ५, ११; १२; १२. २, ४; १९. ३९, ४; ४६, ५.
व्याघ्रऽजम्भनम् ४. ३, ७.
व्याघ्रऽप्रतीकः ४. २२, ७.
व्याघ्रम् ४. ३, ४; ८, ७.
व्याघ्रस्य १९. ४९, ४.
व्याघ्राः १२. १, ४९.
व्याघ्रे ६. ३८, १; ११०, ३.
व्याघ्रौ ६. १४०, १; १२. २, ४३.
व्यानऽउदानौ ११. १०, ४; २६.
व्रः ११. ९, ३.
व्रजः ४. ३८, ७.
व्रजत १९. ७१, १.
व्रजम् ३. ११, ५; ७. ५५, ५; १९. ५८, ४; २०. ७७, ६; ७८, ३.
व्रजस्य २०. ७२, २; ७५, १.
व्रजान् २०. ९०, ३.
व्रजे २०. ८१, २; ९२, २१.
व्रतः ५. १, ७.
व्रतऽचारिणः ४. १५, १३.
व्रततीःऽइव ७. ९५, १.
व्रतऽपते ७. ७८, ४.
व्रतऽपाः १९. ५९, १; २०. २५, ५.
व्रतम् ४. ११, ११; ५. ११, ३; २७, ७; ६. ६४, २; ७. ४१, १; ९. १, ८; ८, ८; १२, ११; १०. ७, १; ११; ११. ९, ९; १८. १, ३३.
व्रतस्य ६. १३३, २.
व्रता २. ३०, २; ३. ८, ५; ६. ७४, १; ९४, १.
व्रतानि ४. ११, २; ७. २७, ६; १८. १, ५; १९. ५९, २; २०. १०९, ३.
व्रते ४. २५, ३; ७. १०, ३; ४१, १[२]; ५१, १; ८८, ३; ८. ९, ८; १८. ४, ६९; २०. २५, ३.
व्रतेन ४. ११, ६; ७. २८, १; ७८, ४; ९५, २; १८. ३, ४०.
व्रतेभिः १९. १०, ९.
व्रतेषु ७. ७०, १.
व्रत्याः ४. ११, ११.
व्रन् १८. ३, २१.
व्राः २. १, १.
व्राजऽपतिम् ७. ७५, २.
व्राजम् १. १६, १.
व्राणाः २०. ३५, १०.
व्रातम् २. ९, २.
व्रात्य १५. ३, १; ११, २[६]; ३; ४; ५; ६; ८; १०; १२, २.
व्रात्यः १५. १, १; ३, ९; १०, १; ११, १; १२, १; १३, १; ३; ५; ७; ९; १८, ५.
व्रात्यऽब्रुवः १५. १३, ११.
व्रात्यम् १५. २, ३; ११; १७; २३; १७, ८.
व्रात्यस्य १५. १५, १; ३; ४; ५; ६; ७; ८; ९; १६, १; २; ३; ४; ५; ६; ७; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; १८, १.
व्रात्याभ्याम् १९. २३, २५.
व्रात्याय १५. ३, ३; १८, ५.
व्रात्येन १५. १२, ४; ७; ८; ११.
व्रीहयः १. ६, १४.
व्रीहिः ८. ७, २०; ९. १, २२; ११. ६, १३.
व्रीहिम् ६. १४०, २.

व्रीहिऽयवाभ्याम् १०. ६, २४.
व्रीहिऽयवौ ८. २, १८; ११. ६, १३; १२. १, ४२.

श

शंसः १९. १०, २[२].
शंसत २०. ८९, १[२].
शंसति २. १२, २; २०. ९४, ८.
शंसन् २०. ९१, १.
शंसन्तः २०. ९१, २.
शंसन्तम् २०. ३४, १५.
शंसन्ति २०. ३७, ९.
शंसन्तीम् १४. १, ९.
शंसम् २०. ८९, ६.
शंसय २०. ७४, १; २; ३; ४; ५; ६; ७.
शंससि ६. ४५, १.
शंसाः २०. १४३, ९.
शंसाति २०. ७७, २.
शंसिषम् २०. ९४, ५.
शंसिषम् २०. ३०, १.
शंस्यम् २०. ३७, ८.
शंस्या २०. ६०, ६; ७१, ६.
शकत् २०. १७, ५.
शकऽधूम ६. १२८, ३; ४.
शकधूमऽजाः ८. ६, १५.
शकऽधूमम् ६. १२८, १.
शकन् ८. ८, २०; ११. १२, १६.
शकऽमर्यम् ९. १५, २५.
शकम्ऽभरस्य ५. २२, ४.
शकल्यऽएषि १. २५, २.
शकाऽइव ३. १४, ४.
शकुनः ६. २७, २; १२. ३, १३; १८. ३, ५५.
शकुनम् १८. ३, ६६.
शकुनयः ११. ११, ९.
शकुनस्य २०. १६, ७.
शकुनाः ११. २, २४; १२. १, ५१.
शकुनिः ७. ६६, १; २.
शकुनैः १०. ३, ६.
शकुनैःऽइव २. २५, २.
शकुन्तान् ११. ८, ८.
शकेत् १२. ४, ९.
शकेम ५. ८, २; १८. २, २९.
शक्तिः २०. २५, ३.
शक्तिऽभिः २. २७, ७; ३. १३, ३.
शक्नः १२. ४, ४.
शक्नवाम १९. ५९, ३.
शक्नुवन्ति ४. २६, ६.
शक्नोति ५. १८, ७.
शक्नोमि ४. ३६, ७.
शक्याम् २०. ७६, ३.
शक्र २. ५, ४; २०. २०, ४; ५७, ७; ८९, ३; १११, २.
शक्रः ३. २१, ४; ३१, २; ४. ११, २; ५. १, ७; ८. ४, २०; २१; ८, १; ५; ७; ९. ४, ५; २०. १७, ६; ७७, ६; ९२, ११.
शक्रम् ७. ९१, १; २०. ५१, ३.
शक्रस्य ८. ८, ६; ८.
शक्राः ५. २८, ८; ११. ८, १२; १८.
शक्राय १२. १, ३७.
शक्वरी ७. २८, १.
शक्वरीः १६. ४, ७.
शक्वरीः ३. १३, ७.
शक्वरीभिः ११. २, २३; १३. १, ५.
शग्धि १९. १५, १; २०. ११८, १.
शग्मः १८. ४, ८.
शग्मा १४. २, १७.

शग्माः ४. २७, ३; १८. २, २१.
शग्मानि १९. ८, २.
शग्मियम् ५. १, ९.
शङ्कवः १०. ८, ४.
शङ्खः ४. १०, १; ३; ४.
शङ्खेन ४. १०, २; ३$^{\text{२}}$.
शङ्खेभ्यः १९. २२, ८; ९; १०.
शचिष्ठया २०. १२४, १.
शचीऽपतिः ३. १०, १२; ६. १३४, १; १३५, १; ११. ११, २०; १२. १, १०; १९. १६, १; २७, १४.
शचीऽपते २०. २७, २.
शचीऽपते ६. ८२, ३; ७. ५७, १; ११. ११, २३; २०. ११८, १.
शचीभिः ५. ११, ८; ७. २६, २; ५५, १; ९. १५, २६; ११. ६, २०; २०. ६३, ३; ७८, ३; १२२, ३; १२४, ६; १२५, ५; १४३, २.
शचीऽवः २०. २१, ३; ७४, २.
शचीऽवः २०. ३३, ३.
शच्या २०. २५, ७; ३३, २; १३७, ७; ११.
शच्याः १३. ८, २.
शणः २. ४, ५.
शतऽअनीकाः २०. ५१, ४.
शतऽअनीकाय १. ३५, १.
शतऽअपाष्ठाम् ५. १८, ७.
शतऽअरित्राम् १७. १, २५; २६.
शतऽआयुषा ३. ११, ३; ४; २०. ९६, ८; ९.
शतऽओदना १०. ९, १.
शतऽओदनाम् १०. ९, ४; ५; ६; १०.
शतऽओदने १०. ९, ३; ७; ११; २४.
शतऽकाण्डः १९. ३२, १; १०; ३३, १.
शतऽक्रतुः ६. ३०, १.
शतक्रतो इति शतऽक्रतो १०. १, ४१; २०. १९, २; ३; ६; २०, १; २; २४, ५; ४५, ३; ५७, ४; ५; ६८, ८; ९; ६९, ६; १०८, १; २; ३; १२२, ३.
शतऽक्रतोः ६. ८२, १.
शतऽतमा २०. ३७, ५.
शतऽतर्हम् १. ८, ४.
शतऽदक्षिण १०. ६, ३४.
शतऽदन् १४. २, ६८.
शतऽदायम् ७. ४९, १; ५०, १.
शतऽधारः ११. १, २०; १२. ३, ५.
शतऽधारम् ३. २४, ४; १८. ४, २९; ३५; ३६.
शतऽधारा १८. ३, ७२.
शतऽपर्वणा ८. ५, १५; १२. ११, ५; २०. १०७, ३.
शतऽपवित्राः १४. १, ४०.
शतऽभिषक् १९. ७, ५.
शतम् १. १०, २; ३०, ३; २. ३, २; ९, ३; १३, ३; ४; २८, १; ४; २९, २; ३. ११, ४$^{\text{४}}$; ५; ७; १२, ६; ४. ३७, ८; ९; ५. १५, १०; ११; ३०, १६; ६. ४४, २; ७७, ३; ९०, २; १३९, १; ७. ३६, २; ५५, २; ८. २, २१; ८, ७; १०. ८, २४; १०, ५$^{\text{३}}$; १२. २, २३; २८; ४, २२; १३. २, ६; ७; ७, १६; १४. १, ५२; २, २; ६३; १९. १३, २; २४, ५; ६; ३०, १; २; ३४, २; ३६, ४$^{\text{२}}$; ६$^{\text{३}}$; ४६, ३; ६७, १; २; ३; ४; ५; ६; ७; २०. १४, ४; ६२, ४; ७६, २; ८१, १$^{\text{२}}$; ९२, २०$^{\text{२}}$; ९६, ९$^{\text{४}}$; १२४, ३.
शतऽमन्युः १९. १३, ७.
शतम्ऽहिमाः १९. ५५, ४.

शतऽयाजम् ९. ४, १८.
शतऽयामना १८. ४, ६०.
शतऽयोनिः ७. ४२, २; १९. ४६, ६.
शतऽवधम् ११. २, १२.
शतऽवधा १२. ७, ९.
शतऽवल्शा ६. ३०, २.
शतऽवारः १९. ३६, १; ३.
शतऽवारेण १९. ३६, ६.
शतऽवाही ५. १७, १२.
शतऽविचक्षणाः ६. ९६, १.
शतऽवीर्यस्य ८. ८, ७.
शतऽवीर्येण ३. ११, ३; २०. ९६, ८.
शतऽवृष्ण्यम् १. ३, १; २; ३; ४; ५.
शतऽशः ६. ६६, ३.
शतऽशल्याम् ६. ५७, १.
शतऽशाखा ४. १९, ५.
शतऽशारदः १०. ३, १२.
शतऽशारदाय १. ३५, १; ३. ५, ४; ११, २; ४. १०, ७; ५. २८, १; ६. ११०, २; ८. २, २; ५, २१; १२. २, ६; १४. २, ७५; १८. ४, ५३; १९. ३७, २; ३; २०. ९६, ७.
शतऽसेयाय ३. १५, ३.
शतस्य १. १७, ३.
शतऽहस्त ३. २४, ५.
शतऽहायनः ८. २, ८; ७, २२.
शतऽहिमाः १९. १२, १; २०. ६३, ३; १२४, ६.
शता २०. २१, ८; ५६, ४.
शतात् १९. ६७, ८.
शतानि ९. १४, १३; १०. ८, ४; १८. ४, ७०.
शतानीकाऽइव २०. ५१, २.
शतिनम् २०. ९, २; ४९, ५.
शते १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५.
शतेन ४. १६, ७; १९, ८; २०. १९, ४.
शत्रवः ४. ३, १; ३१, ७; ५. २०, ३; ६. ६६, ३; २०. ६९, २; १३७, १.
शत्रवः ६. ६६, २.
शत्रवे २०. ९५, ४.
शत्रुः २. २७, १; ५. २, २; ६. ६६, १; २०. ८९, ६; १०७, ५; १३७, १०.
शत्रुऽतूर्याय २०. ३६, १०.
शत्रुम् ४. २२, २; ३; ६. ४, २; २०. ८३, २; ८९, ७.
शत्रुऽयतः ६. ८८, ३.
शत्रुऽयताम् ४. २२, ६; ७; ७. ७७, ९; १०.
शत्रुऽयतीम् ३. १, ३.
शत्रुऽहः १. २९, ५; ६. ९८, ३.
शत्रूणाम् ३. १९, २; ५. २०, ४; ६. ६५, २; ७. ५२, ४; १९. २८, २.
शत्रून् २. ५, ३; २७, ५; ३. १, १; ४; २, ५; ६, १; २; ५; १०, १२; १२, ६; ४. २२, ७; ३१, २; ३; ३२, ३; ५. २, १; २१, ११; ६. ८८, ३; १२६, १; ७. ८९, ३; ८. ८, ६; १०. ३, १; ३; ११; १३. १, ३; १९. १३, ८; ४६, २; ५; २०. ८, १; ११, १; २०, ७; ३५, १३; ५७, १०, ८९, ५; ९०, २; १०७, ४.
शत्रूषाट् ५. २०, ११.
शत्रोः ३. ६, ६.
शत्स्यन्ति ११. ४, ६.
शन्तिऽवा १२. १, ५९.
शन्तिऽवाम् ३. ३०, २.
शपतः ६. ३७, ३; ७. ६१, १.

शपते **१६.** ६, ३.
शपथ **६.** ३७, २.
शपथः **२.** ७, २^{२}; ५; **४.** ९, ५; १८, ७; **५.** १४, ५; **६.** ३७, १; **१०.** १, ५; **११.** १, २२; **१९.** ३८, १.
शपथऽयावनीम् **४.** १७, २.
शपथऽयोपनी **२.** ७, १.
शपथाः **८.** ३, १४.
शपथान् **२.** ७, १; **४.** १९, ७; **७.** ६७, १.
शपथिऽयते **५.** १४, ५; **१०.** १, ५.
शपथेभिः **३.** ९, ५.
शपथेय्यम् **५.** ३१, १२.
शपथ्यात् **६.** ९६, २; **७.** ११७, २; **११.** ८, ७.
शपनेन **१.** २८, ३; **४.** १७, ३.
शपात् **२.** ७, २; **६.** ३७, ३^{२}; **७.** ६१, १^{२}.
शपातः **८.** ३, १२; **१०.** ५, ४८.
शपाति **१.** १९, ४.
शप्तारम् **२.** ७, ५; **६.** ३७, १; २.
शफऽआरुजः **८.** ३, २१; **२०.** ९४, ९.
शफम् **६.** ४६, ३; **१९.** ५७, १.
शफाः **८.** ८, २२; **९.** १२, १०; **१०.** ९, २३.
शफान् **१२.** ७, ८; **९.** ४, १६.
शफेभ्यः **१०.** १०, १.
शफैः **९.** ५, ३.
शबलः **८.** १, ९.
शबलैः **५.** २९, ६.
शबलौ **१८.** २, ११.
शब्दिनः **१९.** ३६, ३.
शम् **१.** ३, १; २; ३; ४; ५; ६, १^{२}; ४^{४}; १२, ४^{४}; ३३, १; २; ३; ४; **२.** ३, ६; १०, २^{२}; ३^{२}; २५, १; **३.** २२, ५^{२}; **६.** १२, ३^{२}; २३, ३; २७, १^{२}; ५७, ३; १२०, २; **७.** २१, २; ७२, १^{५}; **८.** १, ५; २, १४^{२}; ७, १७; **१४.** १, ४०^{६}; २, ४०^{२}; **१८.** १, ५१; २, ३६; ३, ६०^{३}; ४, ९^{२}; ११^{४}; १२; **१९.** २, १^{४}; २^{४}; ७, २; ९, २; ६^{६}; ७^{५}; ८^{४}; ९^{६}; १०^{४}; ११^{७}; १३^{२}; १४^{२}; १०, १^{५}; २^{६}; ३^{६}; ४^{५}; ५^{४}; ६^{८}; ७^{७}; ८^{५}; ९^{६}; १०^{४}; ११, १^{५}; २^{६}; ३^{५}; ६; ४०, ३; ४४, १; **२०.** ४, ३; ६९, ५; ७८, १; १२६, १५.
शमय **७.** ४७, १; **१८.** ३, ६०.
शमयत् **६.** ५२, ३.
शमयतु **६.** १११, २.
शमयन्तु **३.** २१, ८.
शमयामसि **७.** ७८, ३.
शर्मलम् **७.** ६७, २; **१२.** २, ४०; ३, ५२; **१३.** १, ५८; **१४.** २, ६६.
शर्मलात् **४.** ९, ६; **१२.** ३, ५.
शमि **६.** ३०, २; ३.
शमिता **५.** १२, १०; २७, ११.
शमिताय **१९.** ४२, २.
शमितारः **१०.** ९, ७.
शमितारः **९.** ५, ५.
शमीम् **६.** ११, १.
शम्ऽतमः **१७.** १, १०.
शम्ऽतमा **७.** ७१, १.
शम्ऽतमानि **७.** ७०, २.
शम्ऽतमाभिः **१८.** ४, १०.
शम्ऽतमेन **१८.** १, ५१.
शंतातिऽभिः **४.** १३, ५.
शम्ऽताते **१९.** ४४, १.
शम्बः **२०.** ८९, ७.
शम्बरम् **२०.** ३४, ११.
शम्बीऽइव **९.** २, ६.

शम्ऽभु १०. १, ९.
शम्ऽभुः १९. १०, १०.
शम्ऽभुवम् १०. ६, १५; १७.
शम्ऽभूः १४. २, २६; १९. ४६, ६.
शम्यया ६. १३८, ४.
शम्या १९. ४९, ७; २०. २५, ४.
शम्याः १४. २, १६.
शयथा २०. ९१, ५.
शयने ३. २५, १; ५. २९, ८; ९; १८. १, १४.
शयाते इति ८. ४, १३.
शयानः ८. ९, २; १२. १, ३४.
शयानम् ५. २९, ८; ९; ११. १२, २६; २०. ३४, ११.
शयानाम् ७. १०४, १.
शयाम् ५. २५, ९; ६. १३४, २; ११. ११, १९; १२, २२.
शयीय १८. १, १४.
शये १०. ८, २६; १२. १, ४६; २०. ९६, १४.
शये ५. १७, १२; ९. ३, २१; १५, ८; १२. ४, १९.
शरः ११. ३, ६.
शरःऽइव ८. ८, ४.
शरणम् २०. ८३, १.
शरणा ३. १२, ५; १९. १५, ४.
शरणाः १८. ३, ५१.
शरणिम् ३. १५, ४; ६. ४३, ३.
शरणे ६. ५५, २; २०. ३७, ८.
शरत् ६. ५५, २; १२. १, ३६; १५. ३, ४; १९. ६, १०.
शरत्ऽसु १२. ३, ३४; ४१; १८. २, ३८; ३९; ४०; ४१; ४२; ४३; ४४; ४५.
शरदः १. १०, २; २. १३, ३; ४; २९, २; ७; ३. ११, ३; ४; १२, ६; ७. ५५, २; १२. २, २३; १४. १, ५२; २, २; ६३; १८. २, २९; १९. २४, ५; ६; ६७, १; २; ३; ४; ५; ६; ७; ८; २०. ९६, ८; ९.
शरदम् १८. ४, ७०.
शरदि २०. ३४, ११.
शरदे ८. २, २२.
शरभः ९. ५, ९.
शरम् १. २, ३.
शरम्ऽइव ४. ७, ४.
शरवः १. १९, २; ८. ३, १४.
शरवे ४. ३०, ५.
शरव्यया १. १९, ३.
शरव्या ८. ३, १२; १०. ५, ४८; ११. १२, ६; १२. ७, १४; १०, १३.
शरव्याः १. १९, १.
शरव्याम् ५. १८, ९.
शरव्ये ३. १९, ८.
शरस्य १. २, १; ३, १; २; ३; ४; ५.
शरारुः २०. १२६, ९.
शरीः १२. ३, १८.
शरीरम् २. १२, ८; ३. ११, ६; ४. ११, ६; ५. ९, ७; १०, ८; ३०, १३; ७. ५५, २; ८. २, २६; २८; ९. ४, ५; ११. १०, ११; १६; १९; २०; २१; २२; २३; २४; २५; २७; ३०; ३४; १२. ३, २; १८. २, ४; ३, ९; ७१.
शरीराणि ११. २, २.
शरीरे ५. २९, ५; ११. १०, ३०.
शरीरेण ११. १०, २६.
शरीरैः २. ३४, ५; १८. २, ७.
शरुम् १. २, ३; ६. ६५, २; १२. २, ४७.
शर्कराः ११. ९, २१.

शर्कुम् ८. ६, २.

शर्कोटस्य ७. ५८, ५.

शर्दिः १८. ३, १६.

शर्ध ७. ७७, १०.

शर्धः ४. २७, ७; १५. १४, १; १९. १३, १०; २०. १०६, ३.

शर्धते २०. ३४, १०.

शर्धऽनीतिः २०. ११, ३.

शर्म १. २०, ३; २१, ४; २६, ३; २. २८, ५; ५. ३, ७; ८; ६, १२; ६. ७, ३; ५९, १; २; ९२, ३; ७. ७, २; ५१, १; ८. २, ७; ३, १; ७, २५; ९. २, १६; १२. ३, ८; १४; १४. २, २१; ७३; १७. १, १२; १३; १८. २, १९; ४, ९; १९. ९, १२[४]; १६, २; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; २७, १५; ३२, २; ४७, ९.

शर्मणि २०. ६८, ६.

शर्मणे २०. १४२, ५.

शर्मन् २०. १२५, १.

शर्यणाऽवति २०. ४१, २.

शर्वे ८. ८, १७; १८.

शर्वः ६. ९३, १; १२. ८, ९; १५. ५, २; ५[२]; ७; ९; ११; १३; १५.

शर्वम् १५. ५, ४.

शर्वौ ८. ३, ५; २०. ३४, १०.

शर्वाय ६. ९३, २; ११. २, १६.

शलुनान् २. ३१, २.

शल्यः ४. ६, ६.

शल्यःऽइव २. ३०, ३.

शल्यम् ७. ११२, १.

शल्यात् ४. ६, ४; ५.

शल्यान् ८. ३, ६.

शवः ६. ३३, २[२]; ८. ४, ३; ११. १०, ३४[२]; २०. ९, ४; ४९, ७; ६३, ६; ७१, १; ७३, ६; ९९, २; १०४, २; ११८, ४; ११९, २.

शवसः २०. २३, ५; १०४, ४.

शवसः २०. ७५, २.

शवसा ५. २, २; ७; ९; २७, ४; १३. २, ३१; १८. १, ३८; २०. १२, १; १७, ४; ३५, १०; ६४, ५; ७७, ७; ८१, २; ९२, २१; १०७, ५; १०; १२.

शवसे २०. १५, १; १९, १; ५६, १; ५; १४२, ५.

शवांसि २०. ५५, १.

शविष्ठ ७. १०२, १; २०. ६३, ७; ८१, २; ९२, २१.

शविष्ठः २०. ११३, १.

शविष्ठम् २०. ३६, २; ७.

शविष्ठा ७. २६, १.

शशः ५. १७, ४.

शशमानः १८. १, २२.

शशमानम् २. ३४, २; १२. २, १०; २०. ३४, १५.

शशमानाः १८. २, ४७.

शशयानाः ४. १५, १३.

शशयुः ४. ३, ६; ७. ११, १.

शशाक ४. १८, ६; ५. ३१, ११.

शशाप १. २८, ३; ४. १७, ३.

शश्रे ४. १८, ६; ५. ३१, ११.

शश्वत् ४. २४, १; १९. ३२, ७.

शश्वतः १९. ३२, ७; २०. ३४, १०; ३७, १.

शश्वताम् ५. ५, २.

शश्वतीः २०. ७९, २.

शश्वतीनाम् २०. ६४, ३.

शश्वतीभ्यः ५. ८, ८; ६. ७५, २; ३.
शश्वन्ता ९. १५, १६.
शश्वन्ऽवतीनाम् १९. ३६, ६.
शस्तम् १९. ११, ६.
शस्ताऽइव ९. ३, ३.
शस्यते २०. २१, १.
शांशपेन ६. १२९, १.
शाकिने २०. ७८, १.
शाकराः ९. १, ९.
शाखया ३. ६, ८.
शाखा २०. ६०, ४; ७१, ४.
शाखाः १०. ७, ३८.
शाखाम् १. ३४, ४; १०. ७, २१; ११. २, १९.
शाङ्कुरस्य ७. ९५, ३.
शाचिगो इति शाचिऽगो २०. ५, ६.
शाचिऽपूजन २०. ५, ६.
शाण्डऽदूर्वा १८. ३, ६.
शातय १२. ११, ८; १९. ३४, ३.
शातयन् ६. १३५, १.
शातऽवारः १९. ३६, ५.
शान्तः ३. २१, ९[२].
शान्तम् १९. ९, १; २[२]; १४.
शान्ता १९. ९, १[२].
शान्ताः १९. ९, १[२].
शान्तानि १९. ९, २; १३.
शान्तिः १९. ९, ३; ४; ५; १४.[१०]
शान्तिऽभिः १९. ९, १४[३].
शापम् ३. २४, ३.
शामुल्यम् १४. १, २५.
शाम्बुऽभ्यः १९. ३९, ५.
शाम्याकः १९. ५०, ४.
शायय ४. १८, ४.

शारदम् ५. २२, १३.
शारदीः २०. ७५, २.
शारदौ १५. ४, ११; १२.
शारिशाकाऽइव ३. १४, ५.
शार्कोटम् ७. ५८, ७.
शाला ९. ३, १७.
शालाः ८. ६, १०.
शालाऽपतये ९. ३, १२.
शालाम् ३. १२, १; ४; ९. ३, १५[२]; १९[२]; २१.
शालायाः ९. ३, १; २५; २६; २७; २८; २९; ३०; ३१; १४. १, ६३.
शालायाम् ५. ३१, ५; ९. ३, १३.
शालुडम् ८. ६, १७.
शाले ६. १०६, ३; ९. ३, २२.
शाले ३. १२, १; २; ३; ६; ९. ३, ७; ९; ११[२]; १६; २४.
शाशदानः १. १०, १.
शाशदानान् २०. ८७, ४.
शाशदानाम् ८. ४, २४.
शाशद्महे ५. २, ५; २०. १०७, ८.
शासः २०. ७५, २.
शासः १. २०, ४.
शास्मि १२. २, ९.
शिंशुमाराः ११. २, २५.
शिक्याऽकृतः १३. ४, ८.
शिक्यानि ९. ३, ६.
शिकः १०. ६, ३.
शिक्ष १८. ३, ६७; २०. ७९, १.
शिक्ष २०. ८९, २.
शिक्षति २०. ९१, १.
शिक्षते ४. २१, २.
शिक्षन् ९. ४, १; २०. ३७, २.

शिक्षन्तः ६. ११४, २; ३.
शिक्षन्तीः १२. ३, २७.
शिक्षसि २०. ९६, २.
शिक्षात् ७. १३, १.
शिक्षान् ६. १२२, २.
शिक्षाऽनरः २०. २१, २.
शिक्षामि ७. ११४, १; ९. २, १.
शिक्षेयम् २०. २७, २; ८२, २.
शिखण्डिन् ११. २, १२.
शिखण्डिनः ४. ३७, ४; ७.
शिखिऽभ्यः १९. २२, १५.
शिङ्क्ते ९. १५, ७.
शितिऽकक्षाः ५. २३, ५.
शितिङ्गः ११. ७, १२.
शितिऽपदी ११. १२, ६; २०.
शितिऽपात् ३. २९, १; २; ६.
शितिऽपादम् ३. २९, ३; ४; ५.
शितिऽबाहवः ५. २३, ५.
शिथिरम् १०. २, ३.
शिपविलुकाः ५. २३, ७.
शिप्रिन् २०. ७४, २.
शिप्रिन् २०. ४, १.
शिप्री २०. ५३, १; ५७, ११.
शिप्रे इति २०. ३१, ४; ४२, ३.
शिभ्रम् ७. ९५, २.
शिमिदा १२. ८, ९.
शिमिदाम् ४. २५, ४.
शिमीऽवतः १८. १, ६.
शिरः २. २५, २; ३२, २; ४. १४, ७; ५. २३, ९; १३; २९, १०; ६. ४९, २; ५०, १; ८९, १; ९. ५, २१; १२, १; १०. २, २७[२]; ४, ५; ६, १; ७, १८; ९, १३; १०, २; ३; ११. ३, १; १०, १४; १५; १२. १०, १४; ११, ६; १३. ७, १२; १५. १८, ४; १९. २८, ४; ३९, ८; ४९, ९; ५०, ५; २०. २९, ३; ४१, २; १०७, ३; १२६, ५; ७.
शिला १२. १, २६.
शिवऽअपरम् १२. २, ४३.
शिवऽअभिमर्शनः ४. १३, ६.
शिवः २. ६, ३; ३. १४, ५; ६. २७, २; ३; ११६, ३; ७. ४२, १; ८. ९, २२; ९. ४, ७; ५, १२; २०. ७, ३; ३७, १०.
शिवऽतमः १. ५, २.
शिवऽतमाः १९. ८, ६; २०. २१, ११.
शिवऽतमाभिः १८. २, ९.
शिवऽतमाम् १४. २, ३८.
शिवम् ६. ७१, ३; ७. १०६, १; ८. २, १६; १०. ६, ३०; ३४; १२. १, ४६; ४७; १८. ४, ८४; १९. ९, १४; ६४, ३.
शिवया १. ३३, ४; १६. १, १२.
शिवा ३. २८, २; ३[४]; ७. ७१, १; ९. ३, ६; १२. ३, ११; १४. १, ६४; २, १३; १८; १९. ७, ३; ८, ५.
शिवाः १. ६, ४; २. ३, ६; ६. ३, २; २२, २; २३, ३; ७. ४४, १; १२०, ३; ८. २, १४; १५; ७, १७; ९. २, २५; ४, ६; ११. ८, ९; २२; १२. ३, १२; १८. २, ८; १९. २, ५; ४०, ३[२]; ४५, ३.
शिवान् १२. २, २७; १६. १, १३.
शिवानि १९. ८, १; २.
शिवाभिः २. २९, ६; ७. ८९, १; १७. १, १०; २०. ९१, ९.
शिवाम् १२. १, १७; १९. ४९, ५.
शिवे इति २. १०, १; २; ३; ४; ५; ६; ७; ८; ३. ४, ५; ८. २, १४; १९. १४, १.

शिवेन १. ३३, ४; ६. ९३, ३; १३. १, १०; १४. २, ६; १६. १, १२.
शिवौ ६. १४०, १; ८. २, १८.
शिशयम् २०. ८९, ३.
शिशवः १२. ३, ४०.
शिशवे ७. ९९, २.
शिशाति २०. १०६, १.
शिशाधि ४. ३१, ४; ७. १७, १; ८. ४, १९.
शिशानः ८. ३, १; ३; ५; १३. २, ३३; १९. १३, २; २०. ९३, ७.
शिशामि ५. २, ५; २०. १०७, ८.
शिशिरः ६. ५५, २; १२. १, ३६.
शिशीतम् ८. ४, १.
शिशीताम् १८. १, ३१.
शिशीते ८. ३, २४; ४, २०.
शिशीमहि ५. १४, ९.
शिशीहि २०. ५६, ४; ८९, ३.
शिशीहि २०. ३७, ८.
शिशुकः ६. १४, ३.
शिशुम् २०. १०५, २.
शिशु इति ७. ८६, १; १३. २, ११; १४. १, २३.
शिश्नम् ४. ३४, २.
शिश्नथ २०. १७, २.
शिश्नाय २०. ८९, ६.
शिश्नाय १०. २, ७; १३.
शिश्रियाणः १२. १, ३१.
शिश्रियाणम् १. १२, २; २. ५, ६.
शिश्रिये ४. २४, ५.
शिश्रिये १३. १, ६.
शिषः ६. १२७, १; १०. १, १७; ३१.
शिषामहे १८. १, ३७.
शिष्टः २. २९, ४; ३. ५, ४.
शिष्टाः ५. २६, ४.
शिष्टान् २. ३१, ३.
शिष्यते १५. १२, ७; ११.
शीतः ५. २२, १०.
शीतम् ५. २२, १३; १८. २, २२.
शीतऽह्रदा ६. १०६, ३.
शीतान् ८. ९, १७.
शीतार्य १. २५, ४; ७. १२१, १.
शीतिकाऽवति १८. ३, ६०.
शीतिके १८. ३, ६०.
शीपालम्ऽइव २०. १६, ५.
शीपाला ६. १२, ३.
शीभम् ३. १३, २; ५. २०, ७; १२; १३. २, ३; ५; २०. ९४, २.
शीयताम् १८. ३, ६०.
शीरऽशोचिषम् २०. १०३, १.
शीर्यन्ते १२. ४, ३; ५.
शीर्षऽआमयम् ५. ४, १०; ९. १३, १.
शीर्षकपाले इति शीर्षऽकपाले १५. १८, ४.
शीर्षक्तिः १२. ७, १२.
शीर्षक्तिम् ९. १३, १; १२. २, १९; २०.
शीर्षक्त्याः १. १२, ३.
शीर्षणि ३. ७, १; ६. १३८, ३; १०. २, ६.
शीर्षण्यम् २. ३१, ४; ३३, १; ९. १३, १; २; ३; ४; ५; १४. २, ६८; २०. ९६, १७.
शीर्षण्ऽवती १०. १, २.
शीर्षतः ६. १३१, १; १०. २, २६.
शीर्षऽभिद्याय १०. ५, ५०.
शीर्षम् ४. ३४, १.
शीर्षऽलोकम् १९. ३९, १०.
शीर्षाणि १. ७, ७; ८. ३, १५; १०. ४, १९.
शीर्षे ७. ५८, ६; १४. १, ५५.

शीर्ष्णः १. १४, ३; ६. १३७, २; ३; ९. १३, २१; २२^{२}; १४, ५; १९. ६, ८.
शीर्ष्णा ६. ४९, २; ११. ४, १^{२}.
शुक्र् १२. ८, ७.
शुक्रः २. ११, ५; ४. २४, ४; ६. ३४, ५; ५३, १; १३. २, ८; ३४; ४२; १७. १, २०; १८. ४, ५९; २०. १०७, १३.
शुक्रऽपिशम् ५. १२, ६.
शुक्रऽपृष्ठः १३. १, ३३.
शुक्रम् ४. १, ५; १०. ५, ७; ८; ९; १०; ११; १२; १३; १४; १३. ३, १६; २०. ११, ५; १७, ९.
शुक्रऽशोचिः ८. ३, २६.
शुक्रा ५. २७, १.
शुक्राः ८. ७, १; ११. १०, २८; १२. १, १३; ३, २७; १३. २, १.
शुक्रौ १४. १, १०.
शुक्रानि १. २३, २.
शुचः ७. १०५, १.
शुचत्ऽभिः २०. ९१, ७.
शुचन्तः १८. ३, २२.
शुचम् ४. ३८, ४.
शुचयः १. ३३, १; ४; ४. ३४, २; ५. १, ३; ६. ६२, ३; १०. ६, ३; १२. २, ११; २८; ३, २७; २८; २०. ६९, ३; १०४, १.
शुचये ३. १६, ६.
शुचा ३. २५, ४; ५. २०, ३.
शुचि १८. ३, २१.
शुचिः २. ९, ५; ६. ५१, २; ७. ७७, ३; ८. ३, २६; ४, १६; ११. १, १६; २०. १७, ९; ७६, १.
शुचिऽत्वम् १२. ३, २८.
शुचिम् ४. ३४, २; १०. ६, ३.
शुची इति १४. १, १२.
शुद्धम् ७. ७७, ११; ९. १५, २०.
शुद्धऽहस्तौ १२. ३, ४४.
शुद्धा १०. ९, ३.
शुद्धाः ४. २१, ७; ३४, २; ६. ६२, ३; १२२, ५; ७. ७९, १; ११. १, १७; १८; २७; १२. १, ३०; २, ११; १३; २०; २८; ३, २६; १४. २, ६७.
शुद्धाम् ११. १, २३.
शुद्धैः ९. ५, ३.
शुनः ४. ५, २; ६. ८०, १; ३.
शुनम् ३. १५, ४^{२}; १७, ५^{२}; ६^{५}; २०. ११, ११; ९६, ५.
शुना ७. ५, ५.
शुनाम् ३. ९, ४.
शुनासीरा ३. १७, ५; ७.
शुने १. ११, ४; ६. ३७, ३; ११. २, २.
शुन्ध्युः २०. ६६, ३.
शुन्ध्युम् २०. १७, १.
शुन्ध्युवः १३. २, २४; २०. ४७, २१.
शुन्याः ४. २०, ७.
शुभः ६. ३, ३.
शुभः ६. ६९, २; ९. १, १९; १४. १, १५; २, ५; ६; २०. १२५, ४.
शुभम् ८. २, १७; १४. १, ३२.
शुभा १३. १, २१.
शुभे ७. १११, १; १४. १, ५३.
शुभ्राः ११. १, १७.
शुभ्रासः २०. ६७, ४.
शुभ्रिषु २०. ७४, १; २; ३; ४; ५; ६; ७.
शुभ्रे २०. १५, ३.
शुम्भ २०. ९२, १७; १०५, ५.
शुम्भत १२. ३, १३.

शुम्भताम् १८. ४, ६७.
शुम्भाति १४. १, २८.
शुम्भतु १८. ३, ५६.
शुम्भनी इति ७. ११७, १; १४. २, ४५.
शुम्भन्तु ६. ११५, ३; १२. २, ४०.
शुम्भन्ते १२. ३, २६.
शुम्भमानाः ५. १२, ५; ११. १, १४.
शुम्भाति १२. ३, २१.
शुम्भामि ६. ५४, १; २०. ११५, २.
शुरुधः २०. १२, २.
शुल्कः ३. २९, ३.
शुल्कम् ५. १९, ३.
शुशुग्धि ४. ३३, १.
शुशुचीत २०. १७, ९.
शुशुलूकऽयातुम् ८. ४, २२.
शुश्रवत् २०. ६३, ५.
शुश्राव ११. ६, २५.
शुश्रुम ७. ७८, १; ८. ९, १८; ११. १, २९.
शुश्रुवे २०. ९७, ३.
शुश्रूषमाणः २०. ३७, २.
शुषन्तम् २०. ३५, १०.
शुषस्य ५. १, ४.
शुष्कऽआस्या ३. २५, ४; ६. १३९, २; ४.
शुष्के १९. ४९, १०.
शुष्णम् २०. ३७, २.
शुष्णस्य २०. १३७, ११.
शुष्म ५. १, ९.
शुष्मः १. १२, ३; ५. २०, २; ६. ७३, २; ९. ४, २२; १८. २, ३६.
शुष्मम् ३. ९, ३; ६. ६५, १; ९. १, १०; २०; २०. २०, ३; ५७, ६; १०५, २; १०६, १; ११५, २.
शुष्मवत्ऽतरम् ४. ४, ३.
शुष्मा ४. ४, ४.
शुष्मात् २०. ३४, १; १४.
शुष्मिणः ६. २०, १; २०. १७, ३.
शुष्मिणम् २०. १२, ५.
शुष्मिन् ५. २, ४; २०. १०७, ७; १०८, ३.
शुष्मिन्ऽतमम् २०. २०, १; ५७, ४.
शुष्मी २०. १२, ७.
शुष्मे ५. ५, ७; ६. ३८, ३.
शुष्मेण ४. ४, २.
शुष्य ६. १३९, २; ४.
शुष्यतु ६. १३९, २.
शुष्यतु ६. १३९, २; ७. ६१, १; ८. ४, ११.
शुष्यन्तु ६. ९, १.
शूद्रः ४. २०, ४; १९. ६, ६.
शूद्रऽकृता १०. १, ३.
शूद्रम् ४. २०, ८.
शूद्राम् ५. २२, ७.
शूद्राय १९. ३२, ८.
शूद्रे १९. ६२, १.
शून्यऽएषी १४. २, १९.
शूर २. ५, १; ७. ३२, १; ८१, २; ८. ५, १७; ८, ७; १८. १, ३८; २०. १२, ५; २३, ३; ३७, ११; ५६, ५; ७३, १; ७४, ४; ७७, २; ७; ७९, २; १००, २; ११६, २; ११८, १; १२१, १; १२५, १.
शूरः ८. ८, १; २०. ३७, १०; ६०, १; ८९, ४.
शूरऽपत्नि २०. १२६, ८.
शूरऽपुत्रा ११. १, ११.
शूरऽपुत्राम् ३. ८, २.
शूरम् ७. ९१, १; २०. ८९, २.
शूरऽवीरः ८. ५, १.
शूरऽसातौ २०. ९१, ९.

शूरासः १८. २, १७.
शूरेभिः २०. ७०, २०.
शूर्पऽग्राही ११. ३, ४.
शूर्पम् ९. ६, १६; ११. ३, ४; १२. ३, १९; २०.
शूर्पे १०. ९, २६.
शूशुचः १८. २, ४.
शूषम् ५. २, ८; २०. ३०, २; ७१, १६; ९५, २; १०७, ११.
शूषस्य २०. ७२, १.
शृङ्गऽवृषः २०. ५, ७.
शृङ्गाणि ८. ६, १४.
शृङ्गात् ४. ६, ५.
शृङ्गाभ्याम् ९. ४, १७; १९. ३६, २.
शृङ्गे इति २. ३२, ६; ८. ३, २४; २५; ९. १२, १; १०. ९, १४.
शृण १९. ४९, १.
शृणन्तु ८. ३, १४.
शृणवत् ६. २, १; ११. ६, १९; २०. ५३, ३; ५७, १३; ११३, १.
शृणवत् १३. १, ३.
शृणातु ६. १३४, १.
शृणातु ६. ३२, २; १३४, १; १०. ५, ५०.
शृणामि २. ३२, २; ५. २३, ९.
शृणामि २. ३२, ६.
शृणीतम् ६. ५०, १; ८. ४, १.
शृणीमसि २. ७, ५.
शृणीहि ३. ६, २; ५. २९, ४; ८. ३, ४; १०^{२}; १३^{४}; ८, ३; १०. ३, २; ५, ४९^{४}; १३. ३, १७; १६. ७, १२.
शृणु १०. १, २८.
शृणु ५. ८, २; २०. ३, २; ३८, २; ४७, ८.
शृणुत १. ३०, २; २. १२, २; ५. १३, ५; १४. २, ९.
शृणुतम् १८. १, ३१.
शृणुतम् २०. ९१, ११.
शृणुहि २. १२, ३; २०. ८, २.
शृणोत ६. ५०, ३; १८. ३, १९.
शृणोति ४. ३०, ४; ९. ४, १७.
शृणोतु ७. ४९, २; ५०, १.
शृणोतु ५. ३, ११; ७. ५१, २; १३. २, ४४; ४५; १९. १०, ६.
शृणोमि ३. १३, ६; २०. ८९, ३.
शृण्वते १२. २, २१.
शृण्वन् १४. १, ५.
शृण्वन्तः ७. ६३, २.
शृण्वन्तम् २०. ११, ११.
शृण्वन्तु ४. ३५, ७; १८. ३, ३९; १९. ११, ४.
शृण्वे १८. १, २४.
शृतः ९. ५, ५.
शृतम् ४. १४, ९; ११. १, २५; १८. २, ४; ५; ९; ४, १२; १३.
शृतया ४. १४, ९.
शृध्याम् २०. ३४, १०.
शेकिम ६. ११४, ३.
शेकुः २०. ९४, ६.
शेताम् ११. १२, २५.
शेपः ४. ३७, ७; ५. २५, १; ६. ७२, १; १०१, १; १३८, ५; ७. ९५, ३; ९. १२, १३; ११. ७, १२; १४. २, ३८.
शेपःऽहर्षणीम् ४. ४, १.
शेपिषे ५. ३०, ३.
शेपे ७. ९४, ४.
शेप्याऽवते ७. ११८, १.
शेरभ २. २४, १.
शेरभक २. २४, १.

शेरे १०. ३, १५.
शेवऽधिः ७. ५५, ५; १२. ४, १४.
शेवधिऽभ्र्यः ९. ३, १५.
शेवऽधिम् ५. २२, १४; ६. १२३, १; १२. ३, ४६.
शेवलम् १. ११, ४.
शेवा ८. ९, २२.
शेवृध २. २४, २.
शेवृधक २. २४, २.
शेषः १८. २, १०.
शेषणम् ७. ११४, ५.
शेषि ११. ११, १३.
शेषे ५. ३०, ४.
शेषे १८. ३, २.
शैशिरौ १५. ४, १७; १८.
शोकः १. २५, ३.
शोकम् ६. १८, १; १८. १, २९.
शोकात् ४. १४, १; ९. ५, १३.
शोकाय ५. १. ३.
शोकैः ३. २, ५.
शोच २. १९, ४; २०, ४; २१, ४; २२, ४.
शोचत २. २३, ४.
शोचता २. १२, ३.
शोचतु ६. १३०, १; २; ३; ४; १३१, १; २.
शोचय २०. ३६, ८.
शोचयः १८. २, ९.
शोचयामसि ६. ८९, २[2].
शोचयामसि ६. ८९, १.
शोचिः १. २५, २; २. १९, ४; २०, ४; २१, ४; २२, ४; २३, ४; १०. ४, २; १८. २, ८.
शोचिःऽकेशम् १३. २, २३; २०. ४७, २०.
शोचिषा १. १२, २; ६. ३४, २; ८. ३, २३; १७. १, १६; २०. ३६, ८; ६७, ३.
शोचिषे १. २५, ४.
शोचींषि ५. २७, १.
शोणा २०. २६, ५; ४७, ११; ६९, १०.
शोभयामसि १४. १, ५५.
शोभसे २०. १०९, १.
शोशुचत् ४. ३३, १[2]; २; ३; ४; ५; ६; ७; ८.
शोशुचतः ८. ३, १३; १९; १०. ५, ४९.
शोशुचानः ४. ११, ३; ८. ३, ७.
शोशुचानम् ६. १३२, १; २; ३; ४; ५; ८. ३, ९.
शोशुचानाः ५. २२, १.
शोषयति ३. २५, ३.
शोषयामि ६. १३९, १.
शौष्कऽआस्यम् ११. ११, २१.
श्चोतन्ति २०. ८८, ३.
श्नथयन्त २०. १०५, २.
श्नथिता २०. १५, २.
श्नुष्टिः ३. १७, २.
श्नुष्टिम् ८. २, १.
श्मशाने ५. ३१, ८; १०. १, १८.
श्मश्रु ६. ६८, २.
श्मश्रूणि ५. १९, १४; २०. ७३, ५.
श्यामः ८. १, ९.
श्यामम् ११. ३, ७.
श्यामा १. २४, ४.
श्यामेन ९. ५, ४.
श्यावऽअश्वः १८. ३, १५.
श्यावऽअश्वम् ४. २९, ४; ११. २, १८.
श्यावः ५. ५, ८.
श्यावके २०. १२०, २.
श्यावऽदतः ११. ११, १७.

श्यावऽदता ७. ६७, ३.
श्यावम् २०. १६, ११.
श्यावौ ७. १००, १.
श्येनः ३. ३, ३; ४; ६. ४८, १; ७. ४२, १; २; ९. १२, ५; १८. १, २१.
श्येनःऽइव ५. ३०, ९.
श्येनाः ११. ११, ९; १२, २४.
श्येनात् ५. २१, ६.
श्येनीं ६. ८३, २.
श्येनीः १८. ४, ३३; ३४.
श्येने ६. ९२, २.
श्येनौ ७. ७३, ३.
श्यैतम् १५. २, २२; ४, ११; १२.
श्यैतस्य १५. २, २४.
श्यैताय १५. २, २३.
श्रंशयित्वा ४. १६, ७.
श्रत् २०. ३४, ५.
श्रत्ऽदधाति ११. २, २८.
श्रत्ऽदधानस्य ४. ३५, ७.
श्रत्ऽदधानाः ६. १२२, ३; १२. ३, ७.
श्रत्ऽदधानेन ९. ५, ७; ११.
श्रत्ऽधेयम् ४. ३०, ४.
श्रथय १. ११, ३.
श्रथय ७. ८८, ३; १२. ११, १०; १८. ४, ६९.
श्रथ्नानः १४. १, ५७.
श्रद्धाय १२. ५, ३.
श्रद्धा ५. ७, ५; ९. ५, २१; १०. ७, १; ११; ११. ९, ९; १०, २२; १३. ६, २; १५. २, ५; ७, २; ४; ५; १६, ४.
श्रद्धाम् १०. २, १९; ६, ४; १९. ६४, १.
श्रद्धायाः ६. १३३, ४.
श्रपयन् ११. १, ४.

श्रमः ८. ८, ९; ११. ९, १७.
श्रमात् १०. ७, ३६.
श्रमेण ४. ११, १०; ३५, २; ६. १३३, ३; ११. ७, ४; १२. ५, १.
श्रय ९. ५, ४.
श्रयताम् ५. २८, ४.
श्रयते ११. ५, २.
श्रयन्ताम् १८. ३, ५१.
श्रयन्ताम् ५. १२, ५; २८, ३^{२}.
श्रयन्ते १०. ७, ३८; ११. ७, ११.
श्रयस्व ३. ४, २; १२, २; ६. १४२, १; २; ९. ५, ८; १८. ४, ३.
श्रयातै १२. ३, १५; ३८.
श्रयामि ९. ५, ५.
श्रये १९. १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०.
श्रयेथाम् ६. १२२, ३; १२. ३, ६; ७; ९.
श्रवः ६. २८, २; ३३, २; १३. २, ३; २०. २०, ३; ३५, १०; ५७, ६; ७१, १३; १४; ८०, १; १०६, २; १२५, ३; १४२, २.
श्रवःऽसु २०. १९, ७.
श्रवणः १९. ७, ४.
श्रवत् २०. २६, २; ७८, २.
श्रवसा २०. ५८, ४.
श्रवसे २०. १५, ३.
श्रवस्यन्तः २०. ७५, ३.
श्रवस्यवः २०. ६४, ६.
श्रवस्यवः ३. ९, ४.
श्रवस्या २०. १२, १; ३५, ५.
श्रवस्या २०. ४४, २; ६१, ६; ६२, १०.
श्रवस्यानि २०. ९४, ६.
श्रवस्युः ६. ९८, २.

श्रवस्युम् ३. ९, ३; ७. ४१, २.
श्रविष्ठाः १९. ७, ४; ४९, २.
श्रातम् ७. ७५, १; २; ७६, १[२].
श्रान्तम् ६. ७४, २.
श्रान्तसदाम्ऽइव १. ३२, २.
श्रान्तसदौऽइव ७. १००, २.
श्रान्ता ४. २०, ३.
श्राम्यतः ११. १, ३०.
श्रायन्तःऽइव २०. ५८, १.
श्रावयति ९. ११, १.
श्रितः ७. ८०, ३; १२. २, ४४; १३. ३, ५; १४. १, १; २०. १४३, ७.
श्रितम् १. ३२, ४; ६. १८, ३; १०. ८, १९; १३. २, १४.
श्रिता ९. १५, ७; ११. ९, २१; १२. ५, १.
श्रिताः ६. ८०, २; १०. ८, ३४; ११. ३, २०; ८, १२; ९, ४; १४; १३. ३, ६; १८. ४, ४.
श्रिते इति १३. १, ३७.
श्रियः २०. ११०, २.
श्रियम् ४. ८, ३; ५. १२, ६; ६. ५४, १; ७३, १; ९. ५, ३१; ३२[२]; ३३[२]; ३४[२]; ३५[२]; ३६[२]; ८, ६; १०. ६, १०; २०. १४३, २.
श्रिया १०. ६, २६; ११. १, १२; २१; १२. ५, २.
श्रियाम् १२. १, ६३.
श्रीः ११. ९, ३; १२. ६, १.
श्रीणन्ति २०. १०९, २.
श्रीणन्तु ४. १, २.
श्रुत ४. ३०, ४.
श्रुतः १८. १, ३८; २०. २१, ९.
श्रुतम् १. १, २; ३; १५. २, २६; १८. १, ४०; २०. ५१, ३; ७०, २; १०३, १.
श्रुतऽमघम् २०. ७, १.
श्रुतस्य ७. ६३, १.
श्रुतानि ७. ६३, २.
श्रुताम् ६. ५२, ३.
श्रुताय ६. ४१, १.
श्रुतिः ११. ९, २०.
श्रुते २०. ९७, १.
श्रुतेन १. १, ४[२].
श्रुत्ऽकर्णाय १९. ३, ४.
श्रुत्वा ५. ४, २; १२. ४, २७.
श्रुधि २. ५, ४; ४. ३०, ४; १८. १, २५; २०. ८, १.
श्रुधि २०. ७२, ३.
श्रुवन्तु १८. ३, ४९.
श्रूयासम् १६. २, ४.
श्रेयः ५. २०, ९; ७. ९, १; ८. ९, ३२
श्रेयःऽकेतः ५. २०, १०.
श्रेयःऽश्रेयः १०. ६, ५.
श्रेयसीम् १२. २, ४५.
श्रेयांसम् २. ११, १; २; ३; ४; ५; १५. १०, २.
श्रेष्ठऽतमा ६. १३८, १.
श्रेष्ठम् ६. २१, २; ४४, २; ७. ७७, ७; २०. १४१, ३.
श्रेष्ठाः ४. २५, ७; १८. ४, ८६; ८७.
श्रेष्ठेन ५. २५, १०; ११; १२; १३.
श्रैष्ठ्याय १०. ६, ३१; ३२; ३४.
श्रैष्ठ्ये १. ९, ३.
श्रोणिऽप्रतोदिनः ८. ६, १३.
श्रोणिऽभ्याम् २. ३३, ५; ९. १३, २१; २०. ९६, २१.
श्रोणी इति ९. ४, १३; १२, ९; १०. २, ३; ९, २१.

श्रोत्रम् २. १७, ५[२]; ५. १०, ८; ११. ७, २५; ९, २५; १०, ४; २६; १२. ६, ३; १९. ५१, १; ५८, १; ६०, १.
श्रोत्रात् १९. ६, ८.
श्रोत्राभ्याम् ११. ४, २[२].
श्रोत्राय ६. १०, १; १०. ६, ८; १९. २४, ३.
श्रोत्रियः ९. ८, ७.
श्रोत्रियम् १०. २, २०; २१.
श्रोत्रे १९. २४, ३.
श्रोत्रे इति ११. ३, २; १४. १, ११.
श्रोत्रेण २. ३५, ५; १०. ७, ३९; १३. १, १३; १८. २, ५९; १९. ५८, ५.
श्रोमतेन २०. ९७, ३.
श्लोकः १८. १, ३३; ३, ३९.
श्लोकऽकृत् ५. २०, ७.
श्लोकम् १६. २, ४; २०. २५, ६.
श्लोकी २०. ४७, २; १३७, १३.
श्लोणया १२. ४, ३.
श्वः ५. १८, २; ११. ६, २१.
श्वःऽश्वः १०. ३, २; ६, ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७.
श्वऽकिष्किणः ८. ६, ६.
श्वऽघ्नी ४. १६, ५; ७. ५२, ६; २०. १७, ५; ८९, ९.
श्वघ्नीऽइव २०. ३४, ४.
श्वश्रूस्व १८. ३, ५०.
श्वन्ऽवतीः ११. ११, १५.
श्वपदाम्ऽइव ८. ५, ११; १९. ३९, ४.
श्वऽभ्यः ११. २, ३०.
श्वऽयातवः ८. ४, २०.
श्वऽयातुम् ८. ४, २२.
श्वऽवर्तेभ्यः ९. ४, १६.
श्वशुरः १४. १, ३९.
श्वशुरात् ८. ६, २४.
श्वशुराय १४. २, २६.
श्वशुरेभ्यः १४. २, २७.
श्वशुरेषु १४. १, ४४.
श्वश्वाः १४. १, ४४.
श्वश्वै १४. २, २६.
श्वसन्तु ४. १५, १२.
श्वसिहि ६. १०१, १.
श्वा ४. ५, ६; २०. १२६, ४.
श्वाऽइव ४. ३७, ११.
श्वात्र्याः २०. ९६, २.
श्वानः ४. ३६, ६; ११. २, ११; १२, २३.
श्वानौ ८. १, ९; १८. २, ११; १२.
श्वापदः ११. १२, ८; १८. ३, ५५.
श्वापदम् ११. ११, १०.
श्वावित् ५. १३, ९.
श्वासय ६. १२६, १.
श्वित्रः ३. २७, ६.
श्वित्रम् १०. ४, ५; १३.
श्वित्राय १२. ३, ६०.
श्वेत १०. ४, ३.
श्वेतः ५. १७, १५.
श्वेतम् १. २३, ४.

ष

षट् ४. ११, १; २०, २; ५. १५, ६; ८. ९, ७; १६[४]; १७[२]; २३; ९. २, ११; १४, ७; १६; १०. ७, ३५; ८, ५; ११. ३, २१; ९, १८; १३. १, ४; ३, १; ६; १८. २, ६; १९. ४७, ४.
षट् ५. ३, ६.
षट्ऽअरे ९. १४, १२.
षट्ऽअहम् ८. ९, १६.
षट्ऽऋचेभ्यः १९. २३, ३.

षट्ऽपक्षा ९. ३, २१.
षट्ऽपदः १३. २, २७.
षट्ऽभिः १२. २, ४८.
षट्ऽमयूखम् १०. ७, ४२.
षट्ऽयोगम् ८. ९, १६.
षट्ऽयोगेभिः ६. ९१, १.
षट्ऽरात्रः ११. ९, ११.
षट्ऽवृषः ५. १६, ६.
षट्ऽसहस्राः ११. ७, २.
षष्टिः ५. १५, ६; १०. ८, ४; १९. ४७, ४.
षष्टिम् २०. २१, ९.
षष्ठ्याम् १२. ३, ३४; ४१.
षष्ठः १३. ५, ४; १५. १५, ८; १६, ६; १७, ६.
षष्ठम् ८. ९, ६.
षष्ठात् ८. ९, ४; ६.
षष्ठाय १९. २२, २.
षोडशाऽऋचेभ्यः १९. २३, १३.
षोडशम् ३. २९, १.
षोडशी ११. ९, ११.

स

सऽअक्षात् १२. ७, १.
सऽअङ्गाः १८. ४, ६४.
सऽअन्तर्देशाः ९. ५, ३७.
संयती इति सम्ऽयती २०. ३४, ८.
संयतीम्ऽसंयतीम् ९. ५, ३३.
संयत्ऽवसुः १३. ९, ३.
संविदाने इति सम्ऽविदाने २. २८, ४; ७. १३, १; १०. ७, ६.
संशिश्वरीःऽइव २०. ९२, ८.
संसृष्टऽजित् १९. १३, ४.
संस्कृतः २०. ५३, ३; ५७, १३.
संस्कृतम् ११. १, ३५.
संस्कृतत्रम् ४. २१, ४.
संहितऽअन्तम् १०. २, ३.
संहिते इति सम्ऽहिते १२. १, ५२.
सः १. ८, १; १२, १; १६, १; २५, १; २; ३; ३१, ३; ३५, २; २. १, २; ३^{२}; ९, ५^{३}; १२, २; ३४, १; ३. १, १; २, १; ४, ५^{२}; ६^{३}; ६, १; ७, १; १५, १^{२}; ७; १६, ५; २९, ३; ४. १, १; ४^{२}; ५; २, ७; ३, ५; ६, १^{२}; ८; ७, ३; ८, १^{२}; १०, १; ४; ५; ११, २; ३; ७^{२}; १२, ६; १४, १; ९; १५, १०; १६, ४; १८, ६; २१, ५; २३, १; २; ३; ४; ५; ६; ७; २४, १; २; ३; ४; ५; ६; ७; ३०, ४; ३३, ८; ३४, ८; ३६, १०; ३८, ५; ३९, १; ३; ५; ७; १०; ५. ३, ८; ४, ७; ८; ६, १; ८, ४; ५; ९, ७; १०, १; २; ३; ४; ५; ६; ७; ११, ४; १२, ३; १६, ११; १७, ५; ८; १८, २; ४; १३; २२, ९; २४, १; २; ४; ७; ८; ९; १०; ११; १२; १३; १४; २५, ७; २७, ५; २९, २; ३; ३०, १७; ६. १, ३; २, ३; ६, २; १५, १; १६, २; ३३, ३; ३४, १; २; ३; ४; ५; ३६, २; ३९, २; ४६, २; ४७, १; ६३, ४; ७६, ३; ८३, ३; १०९, २; ११०, ३; ११२, १; २; ११९, २; १२२, २; ५; १२३, ३; ४^{४}; ५; १२४, २; १२५, ३; १२६, १; १३३, १^{२}; ७. १, २^{७}; ३, १^{२}; ५, २^{५}; ६, १^{२}; १०, २; १३, १; १८, १; २२, १; ३२, १; ४२, २; ६५, १; ७७, ४; ८०, ४; ८२, २; ८५, २; ९७, १; ११४, १; ५; ८. २, २३; २४; ३, १^{२}; ८; ४, १०; ११; १५; ५, ४; १२; २२; ९, १; २; २२; २५; ९. १, ५; ६; ७^{२};

४, ७; ९; १८; १९; ५, ९; १२; ६, ६^{२};
७, ७; १३^{३}; ९, १; ३; ५; ७; ९; ११,
७; ८; ९; १०; ११; १२; १४, १५^{२}; २२;
१५, ७; ९; १०^{३}; ११^{२}; २४; २८; **१०.**
१, २६; २, ७; ८; ३, ३; ११; १२; ४,
१५; ५, २५; २६; २७; २८; २९; ३०;
३१; ३२; ३३; ३४; ३५; ४४; ५०; ६,
५; ६; ७; ८; ९; १०; ११; १२; १३;
१४; १५; १६; १७; २१; २२; २३; २४;
२५; २६; २७; २८; ३१; ३२; ७, ४; ५;
६; ७; १०; ११; १२; १३; १४; १५;
१६; १८; १९; २०; २२; २४; ३१; ३९;
४०; ४१; ८, १३; १८; २०^{२}; २१; २६^{२};
२८; ३७; ९, ४; ५; ६; १०; १०, २;
२२; २३; २७; **११.** १, ५; २७; २, ८;
११; ३, २३; ५, ५; ६, १४; २०^{२}; २१;
२२; ७, १^{२}; २; ६; २६; ९, १६; १०, ३;
७; **१२.** १, १२; २, ४; ७; १८; ३३;
४७; ४८; ३, ५; १५; १६; ४, २; ६;
१२; १३; ४७; ४९; **१३.** १, १; १३; ५५;
२, ९; १२; २५^{३}; ३७; ३८; ३, १३^{३};
१४; १५; २६; ४, १; ३^{३}; ४^{४}; ५^{३}; ८;
११; १२; ५, ६; ७; ६, ४^{४}; ५; ७, १; २;
३; ४; ५; ६; ७; ८; ९; १०; ११; १२^{२};
१३^{३}; **१४.** १, २९; ३०; २, १; ३३;
३६; ४१; **१५.** १, १; २; ४^{३}; ५^{२}; ६^{२};
२, १^{२}; ३; ४; ९^{२}; ११; १२; १५^{२}; १७;
१८; २१^{२}; २३; २४; ३, १; २; ६, १;
३; ४; ६; ७; ९; १०; १२; १३; १५;
१६; १८; १९; २१; २२; २३; २४; २६;
७, १^{२}; ८, १; २; ३; ९, १; ३; १२, ३;
४; १४, १; ३; ५; ७; ९; ११; १३; १५;
१७; १९; २१; २३; १५, ३; ४; ५; ६;
१६, ६; १७, ७; १८, २^{२}; ३^{२}; **१६.** १,
८; ५, ३; ४; ५; ६; ७; १०; ७, ५; १३;
८, ३; ५; ६; ७; ८; ९; १०; ११; १२;
१३; १४; १५; १६; १७; १८; १९; २०;
२१; २२; २३; २४; २५; २६; २७; २८;
२९; ३२; **१७.** १, ८; ११; १२; २०;
२१; **१८.** १, ६; १६; १८^{२}; २४^{२}; २, ३;
३१^{२}; ५४; ३, ६३; ४, ३५; ४१; ५४;
१९. ४, ४; ६, १; ९; १३, ४^{३}; १५, ३^{४};
१७, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ७^{२}; ८^{२}; ९^{२};
१०^{२}; २६, १; ३१, २; ११; १३; १४;
३२, ९; १०; ३३, १; ३४, ५; ३५, २;
३९, ५; ६; ७; ८; ४६, ५; ४९, १०;
५२, १; ५३, २^{२}; ३; ४^{२}; ५४, ५; ५७,
३; ४; ५८, ४; ५९, ३^{४}; ६४, १; **२०.**
१, १; २; ६, १; ७, ३; ९, ४; १२, ६;
१४, २; ४^{२}; १६, ९^{४}; १२^{४}; १७, ३; ६;
८; २०, ५; २३, ६; ३०, ३; ३१, २; ३४,
१; २; ३; ४; ५^{३}; ६; ७; ८; ९; १०; ११;
१३; १४; १५; १८; ३६, ७; ११; ४६,
२; ३; ४७, १; २^{३}; ४९, ७; ५६, १;
५७, ८; ५८, २; ६१, ६; ६२, २; ४^{२};
१०; ६७, ७; ६९, १^{४}; ७०, १२; ७६, ७^{२};
७७, ८; ८८, ५^{२}; ९१, ७; ९२, १२;
९३, ८; ९४, ५; ९५, १^{२}; ९८, २; १०४;
२; १०८, ३; ११७, २; १२५, ७; १२६,
१६^{२}; १७^{२}; १३७, १२; १३^{३}.

सका १०. ४, १४.

सकृत् २०. ११६, २.

सऽकृतौ ११. १, १०.

सक्तम् ५. १३, १.

सक्थि २०. १२६, ६; ७.

सक्थिऽभ्याम् १०. १०, २१.

सक्थ्याऽ २०. १२६, १६; १७.
सक्थ्यौऽ ६. ९, १.
सक्षणिः ५. ६, ४.
सक्षति ५. २, ७; २०. १०७, १०.
सक्षन्तः २०. ७२, २; ७५, १.
सखा १. २०, ४; २६, २[२]; ५. ४, ७; ११, ९; १०; ११; ६. ५१, १; ७. २७, ६; ५३, १; ८. ३, २०; १८. १, २; ४, ६०; २०. ७, ३; १७, ११; २१, २; ३७, १०; ६८, १०; ८९, ११; ९४, ११; १२४, १; १३७, ६.
सखायः ७. ६२, ४; ७५, २; १४. १, ३४; १८. १, ३७; १९. २४, ७; २०. १४, २; ३; १८, १; २१, ११; २६, १; ३७, ८; ६२, २; ३; ६५, १; ६८, ११; ८५, १.
सखायः ६. ९७, ३; ११. १, २; १२. २, २६; २७; १९. १३, ६.
सखायम् ५. १, ९; ८. ३, २०; १८. १, १; २०. ८९, २.
सखाया ६. ६१, ३; ९. १४, २०; २०. ८६, १.
सखायौऽइव ६. ४२, १, २.
सखिऽभिः ७. ११०, १; १४. १, ५६; २०. ७७, ६; ९१, ३; ७.
सखिऽभ्यः ७. ५३, १; १११, १; ८. ९, ७; २०. १७, ११; २१, २; ६८, ४; ८९, ११; ९४, ११.
सखिऽयतः २०. ७५, ३.
सखीन् ५. २२, ११.
सखीनाम् २०. १२४, ३.
सखीयते १९. ५२, २.
सखे १९. ५२, २.
सख्यम् १८. १, २; २०. ८९, ४.
सख्यऽमि ७. १०९, १.
सख्या ७. ४२, १; २०. २१, ७.
सख्या १८. १, १.
सख्याय ३. ३, २; २०. ६२, ७; ७६, ८; ११४, २; १२५, ३.
सख्युः ५. १३, ५; १८. ४, ६०; २०. ९२, ४; १२६, १२.
सख्ये ८. ९, २२; १३. १, १७; १८; १९; २०. १३, ३.
सऽगणः २०. ६३, २; १२४, ५.
सऽगणाः ७. ८२, ३.
सघत् २०. १५, ४.
संकल्पऽकुल्मलाम् ३. २५, २.
सचताम् १. १२, ३; ९. ४, २२.
सचते ५. १, ७; १२. ३, ५०.
सचते ४. २१, ३; ३४, ३; ३७, ११; १२. ३, २.
सचध्वम् ३. १४, ६; ४. ३७, १२; ६. ४१, ३; ९. ४, २४; १८. ३, १९; ४, ६२.
सचध्वे २. २, ४.
सचन्त ७. ५, १.
सचन्ताम् २. ३४, १; ४. १५, २; ८. ४, १४; १२. ३, ४३.
सचन्ते ६. ११६, ३; १२. ३, ४०; १८. ४, ४०.
सचन्ते ६. १२२, ३; १२. ३, ७; १६; २६[२]; २८; २०. ६, ७; १४३, २.
सचसे ५. ७, ८.
सचस्व १२. २, ५३.
सचा २०. २५, ५; ३८, ५; ४७, ५; ५२, १; ५६, ५; ५७, ११; ६०, २; ६८, १२; ७०, ८; ७१, ९; ७३, ५; ७८, १; ८५, १; १२०, २; १२५, ४.

सचाऽभुवम् २०. ७२, २[२]; ७५, १[२].
सचावहै ६. ४२, १.
सचावहै ६. ४२, २.
सऽचित्ताः ६. १००, १.
सऽचेतसः १. ३०, २; ५. २१, १२; ६. ६८, १; ७. २३, २.
सऽचेतसम् २०. ९४, ४.
सऽचेतसौ २. २९, ३; ४. २६, १; २९, १; २.
सऽचेताः २०. ३५, १०; ७७, ७.
सचेथाम् १२. ३, ९.
सचेवहि १४. २, ७२; २०. ९२, ४; १३.
सजन्तु ५. २१, १०; ११. १२, ३.
सऽजातः १. १९, ३; ३. ३, ६.
सऽजातम् १३. १, ३१.
सऽजाताः ३. ४, ३; ६. ७३, १.
सऽजाताः ३. ३, ४; ६. ७३, २; ३; १८. ४, ३७.
सऽजातान् १. १०, ४; ११. १, ६.
सऽजातानाम् १. ९, ३; २. ६, ४; ३. ८, २; ६. ५, २; १९. ४६, ७.
सऽजातैः ३. ८, ३; ११. १, ७.
सजामि १४. २, ४८.
सऽजित्वानम् २०. ७०, १७.
सऽजूः ६. ३५, २; १२६, १; ८. २, १३; २०. ५४, १.
सऽजोषसः ६. ११५, १.
सऽजोषसम् २०. ९३, ७.
सऽजोषसा २०. १४१, २.
सऽजोषाः ३. २२, १; ४. १४, ५; ३२, २; ५. १२, ३; २८, ५; ७. १८, ३; ११३, २; १२. २, २४.
सत् ५. १९, ९; ८. ४, १२; ९. १५, २८; १०. २, २२; २३; ७, १०; २१; ८, ६; १७. १, १९; २०. २०, ५; ५७, ८.
सतः ४. १, १; ५. ६, १; ८. ४, २१; २०. ५८, ३.
सताम् १. ८, ४.
सति १७. १, १९.
सती ११. १०, १७; १२. ४, १६.
सतीः ९. १४, १५; १२. ३, २६; २०. २८, २; ३९, ३.
सऽतोकान् ६. ५६, १.
सत्तः २०. २३, २.
सत्त्रम् १७. १, १४.
सत्त्रऽसदः १. ३०, ४.
सत्त्रऽसद्येन ९. ९, ६.
सत्त्राणि ११. ९, ८.
सत्त्रेण १२. १, ३९.
सत्ऽपतिः ७. ६४, १; २०. ११, ७; १७, ९.
सत्ऽपतिम् २०. १४, ४; २२, ४; ६२, ४; ९२, १; ९८, १.
सत्पती इति सत्ऽपती ७. ७७, ४.
सत्ऽपते २०. ६, ४; २१, ६; १११, ३; ११२, २.
सत्य २०. ६४, २; ७४, १.
सत्यऽओजाः ४. ३६, १.
सत्यः २०. ३४, १८; ३६, १; ७६, ४; ७७, १; ९५, १; १०४, २; ४; १२४, २.
सत्यऽजितम् ४. १७, २.
सत्यऽधर्मणः १. १०, ३.
सत्यऽधर्मा ७. २५, १; १०. ८, ४२.
सत्यम् २. १५, ५; ३५, ४; ३. १, ४; ४. ९, ७; १८, १; ३४, १; ५. ११, ३[२]; १७, १०; ६. ६१, २; ३; ७. ७३, २; ८. ३, २१; ४, १२; ९. २, २५; ५, २१[२]; १०. २, १४; ३, २५; ६, १५; ७, १; ३७;

११. ९, १७; १०, २०; १२. १, १; ३, १२; ६, ४; १५. १, ३; ६, ५; २०. ९५, १; ११२, २.
सत्यंऽराधः ३. १६, ३.
सत्यऽराधाः २०. ७६, ७.
सत्यऽवर्त्मा ४. २९, ७.
सत्यऽवाचा ५. १, ९; १८. १, २९.
सत्यऽवादिनम् ११. ६, ११.
सत्यऽवादी ४. १६, ६.
सत्यऽवानम् ४. २९, १; २.
सत्यऽशुष्मम् २०. ९४, ३.
सत्यऽशुष्माय २०. १५, १.
सत्यऽसन्धान् ११. ८, १९; २०.
सत्यऽसवम् ७. १५, १.
सत्यऽसवाम् ७. १६, १.
सत्यस्य ३. ११, ८; ६. १, २; १५. ६, ६; १९. १०, २; ११, १; २०. २२, ४; ९२, १.
सत्या १. १०, १; २. ६, १; ५. ३, ४.
सत्याः १२. ४, ८; १९. ४२, ३.
सत्यात् ७. ७३, १.
सत्यानृते इति सत्यऽअनृते १. ३३, २.
सत्याम् २०. २५, ७; ३३, २; ९१, ११.
सत्याय १२. ३, ४६.
सत्यासः १८. ३, ४८.
सत्ये ११. ४, १८; १३. १, ५०.
सत्येन २. ३६, २; १०. ८, १९; ११. ४, ११; १२. १, ८; ५, २; १४. १, १; २०. ९१, ८.
सत्येभिः २०. ९१, ७.
सत्यैः १८. ३, ४७.
सत्रा १७. १, २५; २६; २०. १५, ६; ३२, ३; ५५, १; ५८, ४; ९८, २.
सत्राच्या २०. ११३, १.
सत्राऽजित् २०. ६४, १.
सत्राऽजितः २०. १०, १; ५९, १.
सत्राऽदावन् २०. ७०, १२.
सत्राऽसहम् २०. ११, ८.
सत्वनः ५. २०, ८.
सत्वनाम् ५. २०, ८.
सत्वनाऽयन् ५. २०, १.
सत्वने २०. ७८, १.
सत्वा २०. ३६, १.
सत्वानः ६. ६५, ३; ११. ७, १४.
सत्सि ६. ११०, १; २०. ९४, ९.
सद् २०. ६७, ९.
सदः ७. ७९, २; ९. ३, ७[२]; १९; १३. १, २३; २०. १३, २; ३०, २.
सदः २०. ३, १; १७, २; ३८, १; ४७, ७.
सदःऽसदः ५. १, ४; १८. ३, ४४.
सदःऽहविर्धानानि ९. ६, ७.
सदत १८. ३, ४४.
सदताम् ५. १२, ६.
सदनम् २. ३, ३; १२, ७; ७. ४१, २; ९. ३, ७; ११. १, ३४; १८. २, ५६.
सदना ७. १०२, ४; १८. ३, ५२.
सदनात् ६. २२, १; ९. १५, २२; १३. ३, ९.
सदनाय १९. ११, ६.
सदने ७. १०१, १; १८. १, २५; ३५; ३, ७०; २०. ११, ७; १६, ७; १७, ७; २१, १.
सदनेषु २०. १४०, ५.
सदन्ताम् ५. १२, ८; २७, ९.
सदम् १. १५, ३; ३. १५, ८; १६, ७; ७. १९, २; ११. १, ३४; १३. ३, ११.
सदम्ऽदिः १९. ३९, १०.

सदम्ऽदिम् ५. २२, १३.
सद॑सि ७. ५६, १.
सदा॑ २. ४, १; ३. १६, ७; ४. ४, ७; २७, २; ६. १०१, ३; १२८, ४; ७. २७, ७; १०. ६, १४; ७, ३९; ११. ८, ९; २२; १३. १, १४; १८. १, २२; १९. ११, ५; २०. १२, ६; १७, १२; ३७, ११; ८७, ७; १०१, २.
सदां॑सि १९. ४७, १.
सदान्वा॑ः २. १४, १; ४; ५; ६; ४. १०, ३; १६. ६, ७.
सदान्वाऽक्षय॑णम् २. १८, ५.
सदान्वाऽचात॑नम् २. १८, ५.
सदाऽवृ॑धः २०. ६४, ४; १२४, १.
सदाऽवृ॑धम् २०. ९२, १८.
सदाऽसह॑म् २०. ७०, १७.
सदेम ३. १४, ६; ७. ७८, ४; ११. १, ३४.
सऽदे॑वा १९. ५८, १.
सदोहविर्धा॑ने इति॑ सदःऽहविर्धा॑ने १२. १, ३८.
सद्म॑ ४. १, ४; २०. ३१, ५; ९१, १०.
सद्मा॑नि ५. ३१, ८.
सद्यः २. १, ४; २, ३; ४. ३८, ५; ५. २, १; १२, ११; ६. ८, ३; २३, २; ८. १२, ७; ११. २, २५; ७, ६; १३. २, ६; २०. ९, ४; ३५, ७; १४; ३७, ५; ९; ४९, ७; ६०, ५; ६९, ४; ७१, ५; १०७, ४.
सद्यःऽक्रीः ११. ९, १०.
सद्रु॑ः १५. ७, १.
सधऽमाद॑ः २०. ९४, ३.
सधऽमाद॑म् ६. ६२, ३; १२२, ४; ७. ११४, ३; ५; १४. २, ३४; १८. २, ११; ४, १०.
सधऽमादे॑ २०. ३२, २; ८६, १; ११७, ३; १२२, १.
सधऽमादे॑षु ६. ६२, २; ७. ७७, १.
सधऽमाद्या॑सः २०. ३३, ३.
सधऽस्तु॑तिम् २०. १४३, ६.
सधऽस्थ॑म् २. २, १; ६. ८०, ३; ७. २७, १; १२. १, १८; १३. १, ४४; १४. २, ३६.
सध॑ऽस्थाः ६. १२३, २.
सधऽस्थाः ६. १२३, १.
सधऽस्था॑त् ७. ६५, १; २०. १२३, १.
सधऽस्थे॑ ३. ४, ६; ७. ८७, ६; १०२, ३; १२. २, ७; ३०; १८. १, २५; ३, ७; ८; २०. ९१, ९.
सधस्थे इति॑ सधऽस्थे॑ ७. १०, १.
सऽधु॑राः ३. ३०, ५.
सध्रीची इति॑ १३. ३, १२.
सध्रीची॑ः ६. ८८, ३; ९. ५, २७; १५, ११; १०. ८, ३५; १९. ८, ६; २०. १७, १.
सध्रीचीना॑न् ३. ३०, ५; ७.
सध्र्यङ्ङ् ६. ८९, २.
सन् ४. ११, ३; ५. ८, ३; २२, ९; ६. २६, १; ८. २, ७; ११. ९, ३; १३. १, ३९[२]; १७. १, १२; १८. ४, ५९; १९. ५३, ४; २०. ५३, ३; ५७, १३; ८९, ६.
सनत्वी॑ १०. ८, ३०.
सन॑म् १०. ८, ३०.
सन॑वानि १९. ३२, ७.
सन॑ऽश्रुतः २०. ७३, ४.
सना॑ २०. ३७, ६; ६७, २.
सनात् ५. २९, ११; ६. ११०, १; ८. ३, १८; ९. १४, ११; २०. ११४, १.
सनात॑नम् १०. ८, २२; २३.

सऽनाभिः १. ३०, १; ६. ६, ३; ९. १४, ११.

सनितौ २०. ७१, २.

सनिऽभ्यः २०. ४४, ३.

सनिम् १९. ३१, १४.

सनिषन् ५. ३, ५.

सनिष्णत २०. ७५, ३[२].

सनिष्यवः २०. ७२, १.

सनिस्यदाः १९. २, १.

सनिस्रसऽअक्षेभ्यः २. ८, ५.

सनिस्रसः ५. ६, ४.

सनिस्वनत् २०. ९२, ६.

सऽनीडाः १८. २, २६.

सनुतः ७. ९७, १; २०. १२५, ७.

सनुहि १४. २, ७०.

सनेत् २०. ६९, ७.

सनेम ५. २९, १; १९. १२, १; २०. ६३, ३; १२४, ६.

सऽनेमि ९. १४, १४.

सनेयम् ४. ९, ७.

सन्तः २. ३४, ४; ६. ११७, २; २०. ९१, १०.

सन्तः १९. ५३, ३.

सन्तम् ३. ३, २; ९. १५, ९; १०. १, १८; ८, ३२[२]; १३. १, ३३.

सन्ति ६. १०४, २; ११२, ३; ७. ५, १; ११. २, २८; १९. ४७, ३; २०. ६०, ५; ७१, ५; ९४, ७.

सन्ति ५. ६, ३; १०. १, २०.

सन्तु १. ६, ४[२]; २. ६, २; १२, ६; १४, ३; ३. १९, ७; ४. १८, १; ५. ३, ३; ६, ९; १४, ५; ६. ६६, ३; ७७, ३; १४२, ३[३]; ७. १३, २; ७७, १०; ८. २, १५; ६, १६; ७, ८; १७; ९. २, १०; ४, ६; २०[२]; १०. ९, ३; ११. ८, ९; २२; ११, २; १२, ७; १२. १, ६२; ३, ४२; १४. १, ३४; ४०; १८. २, २०; ३, ५१; ६८; ६९; ४, २५; २६; ३४; ४२; ४३; १९. २, १[२]; २; ८, १; ९, १; ९; १०, २; ३; ४; ७; ८; ११, १; १६, २; २०, २; २७, १५; ४०, ३; ४२, ३; २०. ६९, ५; ९४, ७; १२२, १.

सन्नान् ६. ७६, ४.

सऽपत्नः १. १९, ४; ६. ७५, १.

सपत्नऽकर्शनः ८. ५, १२.

सपत्नऽक्षयणः १. २९, ४; ६; १०. ३, १.

सपत्नऽक्षयणम् २. १८, २; १९. ३०, ४.

सपत्नऽचातनम् २. १८, २.

सपत्नऽदम्भनम् १०. ६, २९; १९. २८, १.

सऽपत्नम् ७. ११४, ३.

सपत्नऽहनम् ९. २, १.

सपत्नऽहा १. २९, ५; २. ६, ३; ४. ८, २; ८. २, २८; ५, १; २; १०. ५, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ६, ३०; १९. ३१, ८; ३२, १०; ४६, ७.

सऽपत्नाः १. ९, २; ४; ४. २२, ६; ३५, ७; ५. ३, १०; २०, २; ९. २, ४; १०; ११; १७; १८.

सऽपत्नान् १. २९, २; २. २९, ३; ३. ५, १; ६, ४; ५. २०, १; २८, १४; ७. ३५, १; ३६, १; ९. २, १; ५; ६; ९; १४; १५; १६; १०. ३, १३; १४; १५; ६, ३०; ११. १, ६; १२. १, ४१; २, ४६; १३. १, २८; ३०; ३१; ३२; ९, २९; १७. १, २४; १९. २८, ५; ६; ७; ८;

९; १०; २९, १; २; ३; ४; ५; ६; ७; ८; ९; ३०, १; ३२, ५; ३३, २; ६६, १.

सऽपत्नानाम् ७. १४, २; १९. २८, ३; ४.

सऽपत्नीं ३. १८, ४.

सऽपत्नीम् ३. १८, १; २; ३; ५.

सऽपत्ने ९. २, २.

सऽपत्नेभ्यः १. २९, ४.

सऽपत्नेषु १०. ९, १.

सपर्य १४. २, १८.

सपर्यत ३. ३०, ६; १८. १, ४९; ३, १३.

सपर्यतः २०. २५, ३.

सपर्यतु १४. २, २३.

सपर्यन्ति २०. १०९, ३.

सपर्यामि १९. ७, १.

सप्त २. १२, ७; ४. ६, २; ११, ९; ३९, १०; ५. १, ६; १५, ७; ६. ३, १; २५, २; ६१, २; ३; ७. ३०, १; ५९, २; ११२, १; ११७, १; ८. ९, १७^{३}; १८^{५}; १९; २३; ९. १, २२; १४, २; ३^{४}; ६; १३; १५, २; १७; १०. २, ६; ८, ९; १०, २^{२}; ३^{२}; ११. ११, ६; १२. १, ३९; २, २९; ३, १६; १३. १, ३७; २, ४; ६; ७; ८; २३; २४; ३, १०; १८; १४. २, ४५; १५. १५, २^{३}; १८. ४, २८; १९. ६, १५^{२}; १६; ३४, ३; ४७, ३; ५३, २^{२}; २०. १७, ३; ३४, ३; १३; ३६, २; ४७, २०; २१; ७७, ३; ९१, १२; ९२, ४; ९; ११०, २.

सप्तऽआस्यः २०. ८८, ४.

सप्तऽऋचेभ्यः १९. २३, ४.

सप्तऽऋषयः ४. ११, ९; ५. १७, ६; ८. १३, १३; १६; ११. १, १; ३; २४; ३, २; १५. २, २२; १९. ९, १२; १३.

सप्तऋषिऽभिः १९. १७, ७.

सप्तऋषिऽवन्तम् १९. १८, ७.

सप्तऽऋषीणाम् ६. ४०, १; १५. २, २४.

सप्तऽऋषीन् ८. १३, १३; १०. ५, ३९; ११. ८, ११.

सप्तऽगृध्राः ८. ९, १८.

सप्तऽचक्रम् ९. १४, ३.

सप्तऽचक्रे ९. १४, १२.

सप्ततिः ५. १५, ७; ६. २५, २; १९. ४७, ३.

सप्ततीः १९. ६, १६.

सप्तथम् ९. १४, १६.

सप्तदशऽऋचेभ्यः १९. २३, १४.

सप्तऽधा ८. ९, २३.

सप्तऽनामा ९. १४, २; १३. ३, १८.

सप्तऽपदः ५. ११, ९; १०.

सप्तऽपुत्रम् ९. १४, १.

सप्तऽभ्यः २०. १३७, १०.

सप्तमऽअष्टमाभ्याम् १९. २२, ३.

सप्तमः १३. ५, ४; १५. १५, ९; १६, ७; १७, ७.

सप्तमम् ९. १, २२.

सप्तऽमातरम् १८. ४, २९.

सप्तयः २०. १३, २.

सप्तऽरश्मिः १९. ५३, १; २०. ३४, १३; ८८, ४.

सप्तऽरश्मौ ९. ५, १५; ११. १, ३६.

सप्तऽरात्रः ११. ९, ११.

सप्तर्षिऽभिः ११. ४, ७; १५. १४, ७.

सप्तर्षिऽभ्यः ७. ५५, ४; १५. २, २३.

सप्तऽवध्रिम् ४. २९, ४.

सप्तऽवृषः ५. १६, ७.

सप्तऽशीर्ष्णीम् २०. ९१, १.

सप्तऽसप्त ४. १६, ६.

सप्तऽहोता ४. २४, ३.
सप्तानाम् ३. १०, ६.
सप्तिम्ऽइव २०. ३५, ५.
सऽप्रथः २०. १८, ६.
सऽप्रथाः १. २६, ३; १८. २, १९.
सऽबन्धवः १०. ३, ९.
सऽबन्धुः ६. १५, २; ५४, २.
सबन्धुऽभ्यः ८. २, २६.
सबन्धू इति सऽबन्धू १०. १, १०.
सऽबन्धून् १५. ८, २.
सऽबन्धूनाम् १५. ८, ३.
सऽबलः २०. ४७, ३; १३७, १४.
सबले इति सऽबले १३. ३, १२.
सऽबाधः २०. १३७. २.
सऽब्राह्मणान् १२. ४, १०; ५३.
सऽभराः ३. १७, २.
सभा ७. १३, १; १५. ९, २.
सभाः १२. १, ५६.
सभागयति ९. ११, ६.
सभागयति ९. ११, ६.
सभाम् ८. १०, ९; १९. ५५, ५.
सभायाः १५. ९, ३.
सभायाम् ५. ३१, ६; ७. ३९, ४; ८. १०, ८.
सभाऽसदः ३. २९, १; ७. १३, २; १९. ५५, ५.
सभासु ४. २१, ६.
सभे ७. १३, २.
सभ्यः ८. १०, ९.
सभ्यः १९. ५५, ५.
सभ्याः १९. ५५, ५.
सम् १. १, ४; ११, २; १५, १[४]; ३; ४; २७, ३; २८, २; २. २, ३; ६, १; २; ४; २६, २; ३[५]; ४[२]; ३०, २[५]; ३१, १; ३२, ३; ३५, २; ३. ४, ३; ६; ८, ५[४]; १०, ३; ८; ११; १२, १; ८; १४, १[४]; २[४]; ५; १५, ८; १६, ६; १९, २[२]; ५; २०, ८; २२, १; २४, ५; २८, १; २; ३१, १; २; ३; ४; ५; ६[२]; ७[२]; ८; ९; १०[२]; ११; ४. २, ७; ८; ४, ४; ५, ५; १२, २; ३[४]; ४; ५[३]; ७; १५, १; २; ३; ६; ७; ८; ९; १७, २; १९, ६; २४, ७; २५, ४[२]; २८, ७; ३०, ८; ३१, ४; ३२, ५; ३४, ३; ४; ३६, ४; ५; ७; ३९, १; ३[२]; ५[२]; ७[२]; ५. २, २; ३; ५; ७; ६, ३; ८, २; ११, २; १४, ९; १८, ५; २२, ६; २३, १०; २८, १; ४[२]; ३०, १३; १४[३]; ३१, १०; ६. ४, ३; ५, १; २; ९, ३; २१, १; ३२, २; ३४, ४; ४५, १; ४६, २; ३; ४८, १; २; ३; ४९, २; ५३, ३[३]; ५६, १; ३[४]; ६३, ४; ६४, १[३]; ६६, १; ७४, १[५]; ८९, ३; ९४, १[४]; ९७, ३; १०२, १[२]; १०३, २[४]; ३; १०४, १; १०९, १; २; ११६, २; ११९, २; १२२, १; ३; १२४, १; १२६, ३; १३१, २; १३५, २[२]; ३[२]; १३९, ३[२]; ५; ७. १०, ४; १७, १; १८, ३; २३, २; ३४, १[४]; ५२, ६; ९; ५४, २[२]; ५५, २; ५८, ४; ७३, २; ७७, १०; ७९, २; ८४, २; ८५, १; ८७, ६; ९४, १[२]; २[३]; ४; १०२, २[५]; १०३, १[४]; ११४, ३; ८. १, १९; २, ३; ४; ५; १३; ३, ३; ४, २; ४; १८; १९; ५, १४; ६, ३; ७, १५; ८, २१[२]; २४; ९, १२[२]; २२; १२, १; ३; ५; ७; ९. १, १४; १५[३]; ३, ३; ४, ११; ५, ६; १४; २४; १३, २२; १४, ३; ८; १५, ९; १८; १०. २, ५; ३, १७[२]; १८[२]; १९[२]; २०[२]; २१[२]; २२[२]; २३[२]; २४[२]; २५[२]; ४,

५; ८; १९; ५, ४३; ४६[२]; ४७[३]; ८, २१; ९, ३; ६; २७; १०, १३[२]; १४[२]; १५[२]; १७; २४; ३३; **११.** १, ४; २, ७; २०; २६; ३, १७; ४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; ६, ६; १०, ८; १४; १५; ११, २; ११[२]; १२[२]; १४; २६; १२, १; ६; ७; ८; १२; २०; **१२.** १, १६; २५; ५३; २, ११; २६; ३१; ३२; ३९; ५५; ३, २; ३[३]; ४; ६; ७; ९; १०; १२; १७; २१; २३; २४; २९; ३०; ३६; ३९; ४५; ५०; ५१; ५५; ५६; ५७; ५८; ५९; ६०; ४, ३; ५; १९; ३१; ११, १[२]; ७; ८; **१३.** १, ८; ३४; ४८; ५०; २, १३; १५; २६[२]; २७; ४०; ३, ४१; **१४.** १, २१[२]; ३१; ३३; ३४[३]; ४०; ४२; ४५; ५२; ५५; २, १२; १७; २९; ३२[२]; ३७; ४०; ५३; ५४; ५५; ५६; ५७; ५८; ६४; ७०[३]; ७१; **१५.** १, १; ३, २; ३; **१६.** ५, ३; ४; ५; ६; ७; १०; ९, ३; **१८.** १, १२; १३; १४; ५३; ५६; ५७; २, ९; १०; २१[२]; २५; २९; ४४; ५८; ३, २; ७; ८[२]; ९; ११; १८; ४०; ५७; ५८[३]; ७१; ४, १; ४१; ४८; ५२; ६०; **१९.** १, १[४]; ३, २; ६, ८; ९; १२, १; १३, ६; २४, ८; २६, २; २७, ५; ७; ३१, १३; ३२, १०; ३३, १; ४०, १; ५२, १; ५; ५३, ४[२]; ५४, १; ३; ४; ५५, १; २; ५७, १; २[४]; ४; ५८, ३[२]; ६९, ३; **२०.** ८, ३; ११, ६; १३, ३; १५, ३; १६, २; २१, ४; ५[४]; ७; २५, ४; २६, ६; ३५, ४; ५; ४०, १; ४५, १; ३; ४७, १२; ५४, २[२]; ३; ५६, ४; ६९, ११; ७०, ३; ५; १९; ७१, ११; १३; ७४, ५; ८९, ९; ९०, ३; ९२, १९; ९४, ४; ९८, २; ९९, १; १०२, १; २; ३; १०७, १; ५; ६; ८; १०; १११, १; २; ३; ११४, २; १२३, १; २; १४२, ३; १४३, ५.

सम्ऽअ॑क्तः **७.** ७८, ४; **१८.** ३, १४.

सम्ऽअ॑क्तम् **५.** २८, १४.

सम्ऽअ॑क्ता **३.** १७, ९.

स॒म्ऽअ॒क्षम् **५.** १४, ४; **८.** ३, ११.

स॒म्ऽअक्ष॑रन् **२०.** १७, ७.

सम्ऽअ॑ग्रः **७.** ८६, ४[२].

स॒म्ऽअ॒ग्राः **८.** ७, १९; **१२.** १, १६.

स॒म्ऽअ॒ङ्कम् **६.** ५०, १.

स॒म्ऽअ॒ङ्कान् **१.** १२, २.

स॒म्ऽअ॒ङ्के **८.** ३, १५; **१२.** ३, १३.

सम्ऽअ॑ङ्गः **१८.** ४, ८.

स॒म्ऽअ॒ञ्जन् **५.** १२, २; १०.

स॒म्ऽअञ्ज॑नम् **७.** ३७, १.

स॒मत्ऽसु॑ **२०.** ११, ११; ३४, ३; ४६, १; ६९, २; ९५, २; १०४, ३.

स॒ऽमद॑ः **५.** २०, १२.

स॒ऽमद॑म् **४.** ३०, ५; **११.** १, ३२.

स॒म्ऽअद॑हः **१८.** ३, ६.

स॒म्ऽअर्घ॑त्थाः **११.** १२, ९.

सम॑नम् **६.** ६०, २[२]; **२०.** १२६, १०.

स॒म्ऽअन॑मन् **४.** ३९, १; ३; ५; ७.

स॒म्ऽअन॑र्तिषुः **१४.** २, ५९; ६१.

सम॑ना **१९.** ५८, १.

स॒म॒ना **२०.** ९७, १; १४३, ७.

सम॑ने **६.** ९२, २.

सम॑नेषु **२.** ३६, १.

सम्ऽअ॑न्तः **७.** ८६, ४[२].

स॒म॒न्तम् **६.** ८, १; ९९, २; ३.

सम्ऽअ॑न्ताः ४. ३४, ५; ६; ७.
सम॑न्ते इति सम्ऽअ॑न्ते १०. ८, १२.
सम्ऽअभ॑रः १. ९, ३.
सम्ऽअभ॑रन् ११. १०, १३.
समम् २. ११, १; २; ३; ४; ५; ४. १८, १;
 १२. १, २.
सम्ऽअम॑मानः १२. ३, ४८.
सम्ऽअये २. ३५, ३.
सम्ऽअरे ५. २०, ५; ७. ८१, २; १०. ८,
 ४२; ११. १२, २५.
सऽमर्यें २०. १२, १; ३७, २.
समऽव॑त्ती ४. १८, १.
सम्ऽअव॑र्तयत् २०. १०७, २.
सम्ऽअव॑ल्गत ३. १३, २.
सम्ऽअशी॑त २०. १५, २.
सम्ऽअश्नुते ३. २२, ५.
समस्य २०. ७६, ४.
सम्ऽअस्य॑ति १२. ४, ९.
सम्ऽअस्व॑रन् २०. ३०, २.
समह ५. ४, १०; ६. २४, १.
समा ५. ११, १०[३].
समा॑ः २. ६, १; ३. १०, ९; ११. ८, १७.
सम्ऽआक॑रत् ६. १४१, १.
सम्ऽआकुर्वाणः १३. १, ८.
सम्ऽआक्ृ॑तम् ४. ३१, ७.
सम्ऽआगा॑ः १२. ३, ३६.
सम्ऽआगृ॑भाय १८. २, ६०.
सम्ऽआचि॑नुष्व ११. १, ३६.
सम्ऽआदर्ध॑ति ६. ७६, १.
सम्ऽआदाय॑ ९. ५, २३.
समानः ६. ६४, २.
समानऽज॑न्मा ८. ९, २२.
समानम् ६. ६४, २[२]; ३; १३९, ३; ८. ९,
 १२; ९. १४, २०; १२. ३, १; ५२; १३.
 १, ४०; १५. १७, ८; १८. ४, २८; २०.
 ३४, ८; ७२, १.
सम्ऽआनम् १०. २, १३.
समानऽलो॑कः ९. ५, २८.
समानऽव॑र्चसा २०. ४०, १; ७०, ३.
सम्ऽआनशे १०. ७, ३६.
समाना ६. ६४, ३.
समानान् ११. १, १२; २१; १५. ५, ३; १६.
समानाना॑म् १६. ३, १; ४, १; १७. १, ५.
समा॑नाम् १. ३५, ४; १४. १, ४.
समानी ३. ३०, ६; ६. ६४, २; ३; १२. ३,
 २२.
समानीः १२. १, ९.
समाने २. १, ५; ३. ३०, ६; १८. १, ८.
समानेन॑ ६. ६४, २.
समानेभ्य॑ः ८. २, २६.
सम्ऽआप॑ १२. ३, ४५.
सम्ऽआ॑प्तिः ११. ९, २२.
सम्ऽआप्याः ११. ३, १९.
सम्ऽआभृ॑तम् ५. २५, १.
समा॑भ्यः ५. ८, ८; ६. ७५, २; ३.
समा॑म् ३. १०, १; १७, ४; १२. १, ३३.
सम्ऽआमे १८. ४, ७०.
सम्ऽआस्याः ४. १६, ८.
सम्ऽआया॑न् १२. ३, ४०.
सम्ऽआव॑ह ३. २४, ५.
सम्ऽआव॑हान् ३. २४, ३.
सम्ऽआस॑ते १२. २, ५१.
सम्ऽआसी॑नानाम् ७. १३, ३.
सम्ऽआह॑र ३. २४, ५; ५. २९, १२.
सम्ऽआहि॑तः ४. ११, ८; १३. १, ५०.
सम्ऽआहि॑तम् १०. ६, ३५; ७, २९; ११.
 ९, १; २; १९. ५३, ७; ८.

समऽआहिताः १०. ७, ११; १३; १९; २२; ११. ९, ८; ९.
समऽआहिताम् ६. ७६, ३.
समाहिते इति समऽआहिते १०. ७, १९.
समऽइत् ७. ९४, ४; १०. ९, ४३; ११. ७, ४; १८. ४, ८८; १९. ६४, ४.
समऽईतयः १२. १, ५६.
समऽईतिः ५. १९, १९; ६. ६४, २; ८८, ३; ७. १३, १; १५. ९, २; १८. १, २६.
समऽईतिम् ८. १०, ११.
समऽईतीः १८. २, ५६.
समऽईतेः १५. ९, ३.
समऽईतौ ८. १०, १०.
समऽईत्याम् १२. ३, ४६; ५२.
समऽईद्धः ५. १२, १; ७. ७७, १; २; ८. ३, १; २; ८, १७; ११. १, ४; ७, ६; १२. २, ११; १८; १३. १, २८; ३, २३.
समऽईद्धम् ७. ७८, ४.
समऽईद्धाः १८. ४, १२.
समऽईद्धे २. १२, ८; १०. ६, ३५.
समऽइधः ५. २२, १; २६, १; २७, १; २९, १४; १५; ८. ९, १८; ९. १५, ३; १९. ६, १५; ६४, ४.
समऽइधम् ६. ७६, ३; ११. ७, १३; १०, २९; १९. ६४, १.
समऽइधा ८. ३, ८; ११. १, ४; ७, ४^{२}; ६; १३. २, ४६; १८. १, ३०; १९. ६४, २.
समऽइधानः १३. १, २८.
समऽइधौ ११. ७, ९.
समऽइषः २०. ५१, ४.
समऽईके २०. ८९, ४; ११८, ३.
समऽईक्षयन् ११. ११, ६; ९; ११; २५.
समीचीः ७. २३, २.
समऽईचीनासः २०. ९९, १.
समीचीने इति समऽईचीने २०. ९४, ८.
समऽईरिरे १४. १, ४६.
समऽउत्पतन्तु ४. १५, १.
समऽउदे ८. १, १९.
समुद्रः ३. २३, ६; ६. ८६, २; ८. ७, २; १०. ७, १५; १०, १६; ११. ३, २०; ९, २; १२. १, ३; १५. ७, १; १६. ३, ६; १९. ११, ३; १९, ७; ३०, ५; २०. १३७, ६.
समुद्रःऽइव ३. २९, ६; ६. १३५, २; ३; १४२, २; २०. ७१, ३; १०४, २.
समुद्रऽजः ४. १०, ४.
समुद्रतः ४. १५, ५.
समुद्रम् २. ५, ६; ३. २९, ७; ४. ८, ७; ६. ४३, २; १०. ५, २३; १०, १३; १५; ११. ७, ६; १३. १, ३६; २, १४; ४०; ४१; ४५; ३, २२; १६. १, ६; २०. ९, ४; ४९, ७; ६३, ८.
समुद्रस्य १. ३, ८; ६. १०५, ३; १०६, २; ९. १, २; १३. ३, ४.
समुद्रस्यऽइव १. ३२, ३.
समुद्राः ९. १५, २१; ११. ८, १०; ९, १४; १३. १, ४२; ३, २.
समुद्रात् २. ३, ४; ४. ५, १; १०, २; ५; १५, ११; २७, ४; ९. १, १; २, २३.
समुद्रान् १९. २७, ३; ४.
समुद्रायऽइव २०. १०७, १.
समुद्रियम् ७. ८, १; १९. ३८, २.
समुद्रियाः ७. ११२, १.
समुद्रियाणि २०. ७७, ७.
समुद्रे १. १३, ३; २. २, ३; ४. २, ५; ३०, ७; ६. ८०, ३; १०. १०, १४; ११. २, २५; ७, २६; २०. ४४, २; १११, २.

समुद्रेण ११. ४, १२.
समुद्रौ ४. १६, ३; ९. ५, २०; १३. २, १०; ३०.
सम्ऽउब्जितः ९. ३, २०; १०. २, २७.
सम्ऽउब्जिताम् ९. ३, १८.
सम्ऽउष्पला ६. १३९, ३.
सम्ऽऊढम् ७. २७, ४.
सऽमूलः ६. १३६, ३.
सम्ऽऊहः ३. २४, ७.
सम्ऽऊहसि १. १३, २; २०. ७२, २; ७५, १.
सम्ऽऋतेषु १९. १३, ११.
सम्ऽऋद्धम् १४. १, ३१.
सम्ऽऋद्धिः ६. १२४, ३; १०. २, १०; ११. ९, १८.
सम्ऽऋद्धीः ११. १, १०.
सम्ऽऋद्ध्या १२. ३, २१.
सम्ऽऋधे ३. १०, १०; १९. ३७, ४.
सम्ऽएतं ७. २२, १; १४. २, २८.
सम्ऽएतः ११. ७, ११.
सम्ऽएतम् १२. ३, ३.
सम्ऽएत्य ११. ८, १८; १२. ३, ४.
सम्ऽएयथुः १२. ३, १.
समेषु ८. ७, १७.
सम्ऽऐति ६. १०२, १.
सम्ऽऐतु ३. २२, ५; ६. १०२, १; ७. ५२, २.
सम्ऽओकसा २०. १४१, २.
सम्ऽओताः ११. ७, २४.
सम्ऽओप्यात् १. १४, ३.
सम्ऽओषन्ती १२. १०, ८.
सम्ऽओहे २०. ७१, २.
सम्ऽकर्षन्ती ११. ११, ८.
सम्ऽकल्पस्य ११. १०, १.
सम्ऽकल्पाः ११. १०, २७; १५. ३, १०.
सम्ऽकल्पान् १६. ६, १०.
सम्ऽकसुकः १२. २, १२; १४.
सम्ऽकसुकम् १२. २, ११.
सम्ऽकसुकात् ८. १, १२; १२. २, ४०.
सम्ऽकसुके ५. ३१, ९; १२. २, १३; १९.
सम्ऽकाशात् ७. ११९, १.
सम्ऽक्रन्दनः ५. २०, ९; १९. १३, २.
सम्ऽक्रन्दनेन १९. १३, ३.
सम्ऽख्याता ४. २५, २.
सम्ऽख्याताः ४. १६, ५; १२. ३, २८.
सम्ऽगच्छै ७. १३, १.
सम्ऽगतानि ६. ४४, २.
सम्ऽगतिम् २०. १४३, १.
सम्ऽगतेषु ७. १३, १.
सम्ऽगत्य ३. ४, ७; ९. ४, १५; ११. ८, २१; १८. २, २६.
सम्ऽगत्याम् ३. २०, ६.
सम्ऽगमः ६. २४, १.
सम्ऽगमनः १०. ८, ४२.
सम्ऽगमनम् १८. १, ४९; ३, १३.
सम्ऽगमनी ४. ३०, २; ७. ८४, ३.
सम्ऽगमने ९. ५, १९.
सम्ऽगमेषु २०. १२५, ३.
सम्ऽगरः ६. ११९, २.
सम्ऽगरम् ६. ११९, ३.
सम्ऽगवः ९. १०, ४.
सम्ऽगिरः ६. १३५, ३; १८. ४, ६०.
सम्ऽगीर्य ६. १३५, ३.
सम्ऽगृणामि ६. ७१, ३; ११९, १.
सम्ऽगृभीताः ८. ४, ८.
सम्ऽगृभ्य ११. ७, ६; २०. २१, ३.
सम्ऽगे २०. ९५, २.

संग्रहणी इति सम्ऽग्रहणी **१९.** ९८, ३.
संग्रामऽजित् **५.** २०, १०.
सम्ऽग्रामम् **११.** ११, २६.
सम्ऽग्रामस्य **५.** २१, ७.
सम्ऽग्रामाः **१२.** १, ५६.
सम्ऽग्रामान् **४.** २४, ७.
सम्ऽघोरम् **१९.** ३५, ३.
सम्ऽचरन्तम् **१८.** ४, २८.
सम्ऽचरन्ति **३.** १५, २; **४.** ३८, ५; **६.** ५५, १; **१२.** १, ४७; **१८.** १, ३६.
सम्ऽजग्मानः **२०.** ४०, १; ७०, ३.
सम्ऽजग्मानाः **३.** १४, ३.
सम्ऽजभार **९.** ३, ११.
सम्ऽजभ्रुः **१२.** १, २४.
सम्ऽजयः **८.** ५, १६.
सम्ऽजयन् **५.** २०, ४.
सम्ऽजयन्तीम् **४.** ३८, १.
सम्ऽजानानाः **६.** ६४, १; **७.** २०, १.
सम्ऽजितम् **२०.** ११, ११.
सम्ऽजित्य **११.** ११, २६.
सम्ऽजीवाः **१९.** ६९, ३.
सम्ऽज्ञपनम् **६.** ७४, २[२].
सम्ऽज्ञपयामि **६.** ७४, २.
सम्ऽज्ञानम् **३.** १४, ४; ३०, ४; **७.** ५४, १[३]; **११.** १, २६.
सम्ऽतन्वतीः **८.** ७, १६.
सम्ऽतरम् **७.** १७, १.
सम्ऽतस्थानाः **२०.** ८९, ४.
सम्ऽतापयन् **१९.** २८, २.
सम्ऽतोदिनौ **७.** १००, ३.
सम्ऽदंशानाम् **९.** ३, ५.
सम्ऽदधाति **६.** १३९, ५.
सम्ऽदधौ **१०.** १, ८.
सम्ऽदानम् **६.** १०३, १[४].
सम्ऽदानेन **६.** १०४, १.
सम्ऽदिताः **८.** ८, ४.
सम्ऽदृशः **७.** ७१, १; **८.** १, ४.
सम्ऽदृशि **१२.** १, १८.
सम्ऽदृशौ **११.** २, ५.
सम्ऽदृष्टा **११.** ११, २.
सम्ऽदेश्यः **४.** १६, ८.
सम्ऽदेश्यात् **१०.** १, ११; **१२.**
सम्ऽदेश्येभ्यः **२.** ८, ५.
संधनऽजित् **५.** २०, ३.
संधनऽजितम् **१७.** १, १; २; ३; ४; ५.
संधनऽजिति **१३.** १, ३७.
सम्ऽधर्या **११.** १०, १६.
सम्ऽधा **११.** १०, १५.
सम्ऽधाता **१४.** २, ४७.
सम्ऽधाम् **११.** १२, ९; १५.
सम्ऽधिम् **१४.** २, ४७.
संधी इति सम्ऽधी **१०.** २, २.
सम्ऽधृता **१२.** १, २६.
सम्ऽनतिः **११.** ९, १३.
सम्ऽनद्धः **६.** १२५, १; **९.** १५, १५.
सम्ऽनद्धा **१४.** २, ७०.
सम्ऽननाहे **६.** १३३, १.
सम्ऽनमः **४.** ३९, १; ३; ५; ७.
सम्ऽनममानः **८.** ३, ६.
सम्ऽनयन् **१९.** ४५, १.
सम्ऽनयन्ति **६.** ४६, ३; **१९.** ५७, १.
सम्ऽनवामहै **२०.** २२, ५; ९२, २.
सम्ऽनशौ **२०.** ९, ४; ४९, ७.
सम्ऽनिषद्य **४.** १६, २.
सम्ऽपतन्ति **१२.** १, ५१.
सम्ऽपतिता **५.** ५, ९.

सम्ऽपत्नी १४. २, २५.
सम्ऽपत्न्यै १४. २, ७३.
सम्ऽपरिवृताम् १०. २, ३३.
सम्ऽपश्यन् १०. ८, १८; १३. २, ३८; ४४; ४५; ३, १४; २५.
संपातिनौऽइव ७. ७३, ३.
सम्ऽपादयन्तौ १२. ३, ३९.
सम्ऽपार्य ६. १३५, २.
सम्ऽपिंषन्ति १४. १, ३.
सम्ऽपिबः ६. १३५, २.
सम्ऽपिष्टः ४. ३, ५; ६. ६, २; १९. ४९, १०.
सम्ऽप्रयच्छ १०. ५, ४५.
सम्ऽप्रयतीः ३. १३, १.
सम्ऽप्रश्नम् २. १, ३.
सम्ऽप्रिया २. ३६, ४.
सम्ऽप्रेद्धः ६. ७६, १.
सम्ऽबभूव ३. २२, १; ३; ४. ३५, ६; १०. ७, ३१; १२. १, २३; ३, ३.
सम्ऽबभूविथ ४. १९, ७.
सम्ऽबभूवुः ६. ७४, ३; १२. १, ३; ४; १२; ३, ४०; १३. १, १०; १८; १९. ४, ४.
संबाधऽतन्द्र्यः १०. २, ९.
सम्ऽभक्ताः ८. ७, १२.
सम्ऽभरन्ति ९. १, १६.
सम्ऽभलः २. ३६, १; १४. १, ३१.
सम्ऽभलस्य १४. २, ६६.
सम्ऽभले १४. २, ६७.
सम्ऽभाराः ९. ६, १.
सम्ऽभारान् ११. १०, १३.
सम्ऽभुञ्जती ३. १०, ७.
सम्ऽभुञ्जतीभ्यः ११. २, ३१.
सम्ऽभूतम् १२. ४, ३३.
सम्ऽभूता ६. १००, ३.
सम्ऽभूय १०. ८, ११.
सम्ऽभृतः ५. २०, १; २१, ३; २०. ४७, ३; १३७, १४.
सम्ऽभृतम् २. ३६, २; ४. १४, ९; ७. ९८, १; ९५, २; ८. ७, १८; ९. ४, ८; १०. २, १; १९. ६, १४.
सम्ऽभृतश्रीः १९. ४९, १.
सम्ऽभृता १०. १, २; २४; १९. २२, २१; २३, ३०.
सम्ऽभृताम् ३. १२, ८.
सम्ऽभृते १०. ३, २०.
सम्ऽभृत्वा ३. २४, २.
सम्ऽमनसः ३. ३०, ५; ७; ६. ७३, १; ७४, ३; ८८, ३; ७. २०, १; ९९, १; ९. ५, ३७; ११. ७, १; ८.
सम्ऽमनसौ ६. ४२, १.
सम्ऽमनाः ३. ३०, २.
संमातरःऽइव ८. ७, २७.
संमातरौऽइव १३. २, १३.
सम्ऽमाता १३. १, १०.
सम्ऽमितः १२. ३, ३३.
सम्ऽमितम् ३. २९, ३; ४; ५.
सम्ऽमिताः १२. ३, २०; २८.
सम्ऽमितासः १२. ३, २७.
सम्ऽमिश्लः २०. ३८, ५; ४७, ५; ७०, ८.
सम्ऽमिश्लाः २०. ६७, ४.
सम्यक् १८. ४, ११.
सम्यञ्चः ३. ३०, ३; ६.
सम्यञ्चम् १३. ३, २०.
सम्यञ्चौ ५. १, ५.
सम्ऽयतम् ६. ५६, १; १०. ४, ८.
सम्ऽयतम् २०. ३६, १०.

स॒म्ऽय॒तोः १६. ८, २९.
स॒म्ऽयन् ९. ५, ३३.
स॒म्ऽयन्त॑म् ९. ५, ३३.
स॒म्ऽयन्ति॑ ४. ११, १२; ६. २५, १; २; ३.
स॒म्ऽयम॑ः ४. ३, ७^{२}.
सम्ऽयु॑तम् ६. ३०, १.
सम्ऽर॑ब्धम् १३. १, ४.
स॒म्ऽरभ्य॑ १९. १, ३.
स॒म्ऽर॒रा॒णः २. ३४, ३; ४; ७. १८, ४; १८. ३, ४६.
स॒म्ऽराज॑म् २०. ४४, १.
स॒म्ऽराजे॑ १७. १, २२; २३.
स॒म्ऽराज्ञी॑ १४. १, ४३; ४४^{४}.
स॒म्ऽराट् ४. १, ५; ६. ३६, ३; ८६, ३.
स॒म्ऽरा॒धय॑न्तः ३. ३०, ५.
स॒म्ऽरुध॑म् ७. ५२, ५.
सम्ऽलि॑खितम् ७. ५२, ५.
स॒म्ऽलुप्य॑ १०. १, ३०.
स॒म्ऽलो॒भय॑न्तः ६. २८, १.
स॒म्ऽवत॑म् ६. २९, ३; १०५, २.
स॒म्ऽव॒त्स॒रः ३. १०, ८; ४. ३५, ४; ८. ८, २३; १०. ६, १८; ११. ७, २०; ९, १८; १५. १७, ७; १८, ४.
स॒म्ऽव॒त्स॒रम् ४. १५, १३; १०. २, २०; २१; १५. ३, १; १७, ८; १९. ५८, १.
स॒म्ऽव॒त्स॒रस्य॑ १. ३५, ४; ३. ५, ८; १०, २; ३; ५. २८, १३; ११. ८, २२.
स॒म्ऽव॒त्स॒राः २. ६, १.
स॒म्ऽव॒त्स॒रान् ३. १०, ९; ११. ८, १७.
स॒म्ऽव॒त्स॒राय॑ ६. ५५, ३.
स॒म्ऽव॒त्स॒रीण॑म् ८. ३, १७.
स॒म्ऽव॒त्स॒रीणा॑ः ७. ८२, ३.
स॒म्ऽव॒त्स॒रे ८. १२, १; २; ९. १५, २६.
स॒म्ऽव॒त्स॒रेण॑ १०. ७, ५.
स॒म्ऽव॒त्स॒रेभ्य॑ः ३. १०, १०; १९. ३७, ४.
स॒म्ऽवद॑न्ति ४. ३७, ५.
स॒म्ऽवन॑नम् ६. ९, ३.
स॒म्ऽवन॑ना २०. ८५, २.
स॒म्ऽवन॑नी ६. १३९, ३.
स॒म्ऽवन॑नेन ३. ३०, ७.
स॒म्ऽवर॑णे २. ६, ३.
स॒म्ऽवर्ग॑म् २०. १७, ५.
स॒म्ऽवस॑न्तः ७. ८४, १; ८५, १.
सम्ऽव॑सवः ७. ११४, ६.
स॒म्ऽवसा॑नौ १२. ३, ५२.
स॒म्ऽवह॑न्ति १३. ३, १७.
स॒म्ऽवि॒जन्ते॑ ५. २१, ४; ६.
स॒म्ऽविद॑ः ३. ५, ५.
स॒म्ऽविद॑म् ९. ८, ६; १८. १, १६.
स॒म्ऽवि॒दा॒नः ३. ४, ६; ४. १५, १०; ५. २९, २; ३; ६. ६३, ३; ८४, ४; १२. ३, ८; १३. १, ३५; १६. ६, ६^{२}; १८. १, ६०; ३, ८; १९. ४०, १; २०. ९६, ११.
स॒म्ऽवि॒दा॒नम् ५. २८, ५.
स॒म्ऽवि॒दा॒ना ६. ३८, १; २; ३; ४; ७. ७३, १; १२. १, ४८; ६३; १६. ६, ५^{२}.
स॒म्ऽवि॒दा॒नाः ३. ४, ७; ५. २८, २; १०. ७, ५.
स॒म्ऽवि॒दा॒नौ २. २८, २; ३. १५, ४; ११. २, १४.
स॒म्ऽवि॒दुः ३. २१, ५; १०. ८, ४१.
स॒म्ऽवि॒द्म ११. ८, ९.
सम्ऽवि॑द्यम् १२. ४, ४.
स॒म्ऽवि॒द्वान् १. २५, १; २; ३.
स॒म्ऽविन्दते॑ ३. १८, १.
स॒म्ऽविवृ॑त्सति ८. ६, १६.

सम्ऽवृक् २०. ३४, ३.
सम्ऽवृतः २०. ९, १.
सम्ऽवृतः १८. ३, ३०; ३१; ३२; ३३; ३४; ३५.
सम्ऽवृतम् ८. ६, ४.
सम्ऽवेशने १८. ३, ७.
सम्ऽवेशयन् ३. ८, १.
सम्ऽवेश्यमि ३. ८, १.
सम्ऽशश्रे ४. १२, ७.
सम्ऽशार्य ७. ८९, ३.
सम्ऽशितः ५. २०, १०.
सम्ऽशितम् ३. १९, १[३]; ६. १०४, २; ७. १७, १; १२. १, २१.
सम्ऽशितानि १९. ९, ५.
सम्ऽशिशानाः ४. ३१, १.
सम्ऽशिषः ११. १०, २७.
सम्ऽश्रिता ११. ९, २१.
सम्ऽश्रुतम् १. ३, ६.
सम्ऽश्रेषिणे ८. ५, १४.
सम्ऽसदः ७. १२, ३; २०. ११०, २.
सम्ऽसदम् २०. २९, ५.
सम्ऽसदि २०. १३, ३.
सम्ऽसम् ६. ६३, ४.
सम्ऽसमकम् ६. ७२, १.
सम्ऽसिक्ताः २. २६, ४.
सम्ऽसिचः ११. १०, १३.
सम्ऽसिच्य ११. १०, १३.
सम्ऽसीव्य १०. २, २६.
सम्ऽसुदे २०. ४, ३.
सम्ऽसृजति ४. २४, ७.
सम्ऽसृजन्ति ४. २७, ५.
सम्ऽसृजि ४. ३१, ६.
सम्ऽसृष्टम् ४. ३१, ७.
सम्ऽस्कन्धम् १९. ३४, ५.
सम्ऽस्थितः १८. ४, १५.
सम्ऽस्थे २०. ६९, २.
सम्ऽस्पर्शे ८. २, १६.
सम्ऽस्फान ६. ७९, ३.
सम्ऽस्फानः ६. ७९, १.
सम्ऽस्रवन्ति १. १५, ३; ४.
सम्ऽस्रष्टा १९. १३, ४.
सम्ऽस्रावणाः १. १५, २; १९. १, २.
सम्ऽस्रावैः १. १५, ३; ४.
सम्ऽस्राव्येण १. १५, १; २. २६, ३; १९. १, १; २; ३.
सम्ऽहनु ५. २८, १३.
सम्ऽहनुः ८. १, १६.
सम्ऽहितः ३. ३१, ६; १३. ६, ५; १९. २७, ७.
सम्ऽहितम् ११. १०, १६.
सम्ऽहितम् १३. ३, १०.
सम्ऽहिताः ७. ७९, २.
सम्ऽहोत्रम् २०. १२६, १०.
सऽयावरीः २०. १०९, १.
सऽयुजा ५. १४, ७; ७. ११३, २; ९. १४, २०; ११. १, ९; २, १४.
सऽयुजौ ६. १४०, ३; ७. ५५, २.
सऽयोनयः ७. २०, १.
सऽयोनिः ३. ५, ८; ६. १२२, ४; ९. १५, ८; १६; १२. ३, १९; ५३; १९. ५२, १,
सरः २०. २२, ३.
सरण्यूः १८. २, ३३.
सऽरथम् ३. २१, ३; ४. ३१, १; ९. २, ९; १८. १, ४३; ३, ४८; ४, ४७; १९. ५६, १; २०. १३, ४; १४१, २.
सरमा २०. ७७, ८.

सरमायै ९. ४, १६.
सरस्वति ७. ११, १; ७०, १; १८. १, ४३, ४, ४७.
सरस्वति ४. ४, ६; ५. २५, ३; ६. ९४, ३; ७. ७०, २; ७१, १; १४. २, १५.
सरस्वती ५. २३, १; २५, ६; २७, ९; ६. ३, २; ८९, ३; ९४, ३; ७. ५९, १; १६. ४, ४; १८. १, ४१; ४, ४५; १९. १९, २; ३१, ९; १०; ४०, १; २०. १२५, ५.
सरस्वतीः ५. १२, ८; ६. १००, १.
सरस्वतीम् ३. २०, ७; ५. ७, ४; १८. १, ४१^{३}; ४२; ४, ४५^{३}; ४६.
सरस्वत्या ५. ७, ५; १०, ८.
सरस्वत्याम् ६. ३०, १.
सरस्वत्यै ६. ४१, २; १४. २, २०.
सरस्वन्तम् ७. ४१, १; २; ९. ४, ९.
सरा ५. ५, ९.
सरितः १२. २, ४१.
सरिष्यथ ३. ९, ५.
सरीसृपम् ३. १०, ६; १९. ४८, ३; २०. ९६, १३.
सरीसृपाणि १९. ७, १.
सऽरूपः १. २४, ३.
सरूपऽकृत् १. २४, ३.
सऽरूपम् १. २४, ३.
सरूपम्ऽकरणी १. २४, ४.
सऽरूपा १. २४, ३.
सऽरूपाः १८. ४, ३३.
सऽरूपाम् १. २४, २.
सऽरूपौ ५. २३, ४.
सरौ ५. २५, १.
सर्गाः ४. १५, २; ३; ४.
सर्जतः ५. ३०, ५.
सर्तवे २०. ३४, १३.
सर्तवै २०. १५, ६.
सर्प २. २४, ४.
सर्प ३. २५, ४; १८. ३, ४९.
सर्पः ११. ४, १६; १२. १, ४६; १८. ३, ५५.
सर्पत् १२. १, ४६.
सर्पत १८. १, ५५.
सर्पतु २०. ५, १.
सर्पन्तम् ४. २०, ७.
सर्पन्तु ५. ११, ६; ११. १, १७.
सर्पम् १२. १, ३७.
सर्पाः ११. १२, १.
सर्पाः ८. ७, २३; १४, १३; १६; ११. ११, १६.
सर्पान् ८. ८, १५; १४, १३; ११. ८, १६; ११, २४.
सर्पिः ९. ९, ३; १०. ९, १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; १२. ३, ४५.
सर्पिषः १. १५, ४; २०. ६७, ३.
सर्पिषा १२. २, ३१; १८. ३, ५७.
सर्पेभ्यः १०. ४, २३.
सर्व १९. ९, १४.
सर्वऽअङ्ग ८. १, २०; २०. ९६, १०.
सर्वऽअङ्गः ८. २, ८; ११. ४, १^{२}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{२}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; १२^{२}; १३^{२}; १४^{२}; १५^{२}; १६^{२}; १७^{२}; १८^{२}.
सर्वऽआत्मा ५. ६, ११; १२; १३; १४.
सर्वः १. ७, ४; १५, २; ३. १६, ५; २०, ६; ८. २, २५; ९. ७, ८; ९; १६. ४, ६; १८. ४, ८; १९. ५१, १.

सर्वकम् **१**. ३, ६; ७; ८; ९.

सर्वऽकेशकः **४**. ३७, ११.

सर्व॑ऽगणः **१६**. ४, ६.

सर्व॑ऽगुः **५**. ६, ११; १२; १३; १४.

सर्वऽजन्मनः **११**. ६, २४.

सर्वऽज्यानिः **१२**. ७, ११.

सर्वऽज्यानिम् **११**. ५, ६; ७.

सर्वतः **३**. २, २; २०, १०; **४**. १०, ५; **५**. १३, ७; २८, १०; **६**. ६७, १; ८४, १; **८**. ५, ४; १९; २२; **१०**. ८, १०; **११**. ९, ४; **१४**. १, ६४; **१९**. १६, २; २७, १५.

सर्व॑ऽतनूः **५**. ६, ११; १२; १३; १४; **११**. ४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२].

सर्वऽताता॑ये **६**. ३, ३.

सर्वदा **१**. ३२, ३; **९**. ७, १०; **१०**. ६, ३२; ७, २३; ९, १२; **१२**. २, ५०; ५१; **१८**. ४, २९.

सर्व॑ऽपरुः **११**. ४, १[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]; ७[२]; ८[२]; ९[२]; १०[२]; ११[२]; १२[२]; १३[२]; १४[२]; १५[२]; १६[२]; १७[२]; १८[२].

सर्व॑ऽपात् **१०**. १०, २७.

सर्व॑ऽपुरुषः **५**. ६, ११; १२; १३; १४; **१०**. ३, १०.

सर्व॑म् **१**. १८, ३; **२**. ७, २; ३१, ५; ३६, ६; **३**. ७, ३; ७; **४**. ५, ७; १६, १; ५; १७, ६; ७; १८, ८; २०, १; ४; ८; २२, २; **५**. ४, ९; १०; ८, ६; १८, ४; **६**. ६, १; १४, १; २४, २; ४६, ३; ५४, ३; ५७, ३; १०७, १; २; ३; ४; **७**. २१, ६; ६७, ३; ८०, ३; १०६, १; ११९, १; **८**. १, २०[२]; २, १२; १९; १०, १; १४, १२; **९**. ४, २०; ५, १९; २३; १२, २४; १३, १; २; ३; ४; ५; **१०**. १, १०; १३; २५; ३२; ६, १८; ७, २९; ३०; ८, १; २; ६; २१; ३०; ९, २७; १०, २६; ३४; **११**. २, १०; ६, १[२]; ४; १५; १०, १३; १५; ११, १; १०; १२, १७; **१२**. २, २; २४; ३६; ३, २८; ५२; **१३**. १, ५४; ५५; २, ४१; ४५; **१९**. ६, ४; ९, २; १४; ३४, १; ३९, १; ५; ६; ७; ८; ४४, २; ५२, ५; ५७, १; ५; ६१, १; ६४, ३; ६९, १; २; ३; ४; ७०, १; **२०**. २५, ४; ७४, ७; ९६, १०[२]; ११२, १.

सर्वऽरथा **२०**. ९६, १.

सर्व॑ऽरूपम् **९**. १२, २५.

सर्व॑ऽरूपाः **९**. १२, २६.

सर्व॑ऽवित् **६**. १०७, ४.

सर्वऽवित् **१७**. १, ११.

सर्वऽविदे॑ **६**. १०७, ४.

सर्व॑ऽवीरः **७**. १०, २.

सर्व॑ऽवीरम् **३**. २०, ८; **७**. ९, १; **११**. १, ३; ११; **१४**. २, ६; **१८**. ३, १४; ४४; ४, ४०; **१९**. ३१, १३; १४; **२०**. १३, १.

सर्व॑ऽवीराः **३**. १२, १; ६; **१२**. २, २८; **१९**. ४९, ६.

सर्व॑ऽवेदसः **१९**. ४९, ६.

सर्वऽवेदसम् **९**. ५, १७.

सर्व॑स्मात् **७**. ६६, १; **१०**. १, ११; ३, ४; ५, २२.

सर्व॑स्मै **३**. २८, ३; **४**. १७, १; **९**. ४, २; **११**. ६, ८; **१३**. ५, ६; **१९**. ३२, ८.

सर्व॑स्य **११**. ६, १; १०; २४; **१२**. १, ३४; **१९**. ५३, ८; ६२, १.

सर्वैस्याः ७. १३, ३.

सर्वैस्यै १४. २, २७.

सर्वैऽहायसः १०. ५, २३.

सर्वैऽहायाः ८. २, ७.

सर्वऽहुतः १९. ६, १३; १४.

सर्वैऽहुतम् १८. ४, १३.

सर्वऽहृदा २०. ९६, ३.

सर्वा २. १, ३; ४, ४; ४. ५, ४; ११, २;
  २०, २; ६. १२४, ३; ७. ८८, १; ८. ७,
  १४; १०. ५, ५०; ११. १, ३१; ८,
  २१; १२. १, ५०; ९, ४; ११, १०; १३.
  ६, ७; १४. २, २४; १८. २, ६; १९.
  ३१, ११; ६०, २.

सर्वाः २. १४, १; ३; ३. ४, १; ७[२]; २०,
  ९; ४. ५, २; ३; ८, ४; ९, ९; १७, २;
  ५; १८, ५; ७; ८; २२, ७; ३४, ५; ६;
  ७; ३५, ५; ६. २४, ३; २५, १; २; ३;
  ८७, १; ८८, ३; ७. १०, २; २४, १;
  ४४, १; ७८, १; ८. ५, ८; १३; ७, १;
  १९; ९, २२; ९. १, १; ५, ३७; १०. १,
  ४; ३०; २, २८; ११. ६, ६; १९; ८,
  ६; १०, २१; ३२; ११, १५; १२. ३,
  ३१; १३. १, २०; २६; २, २; ४१; ३,
  १९; २०; १५. ६, २२; १८. ४, ६; १९.
  ३, २; १५, ६; ३४, ९; ३९, १; ५; ६;
  ७; ८; ४४, ७; ४५, ४; ५३, ७; ५६, ६;

सर्वाणि १०. ७, ४०; १२. ६, ५; ७, २; ३;
  १९. ८, १; ९, १३.

सर्वान् २. ७, १; १४, ६; ३१, २; ३. ५,
  ६; ७; ६, ३; १०, ७; २९, २; ३०, ७;
  ४. ३, ३; ९, ९; १६, ९; १९, ७; २०,
  ६; २२, १; ३६, ३; ४; ३७, २; १०;
  ३८, ५; ५. २३, ६; ८; ६. ५०, ३; ८०,
  २; ११२, २; ११७, १; ३; ११९, २;
  १२१, ४; ७. ६७, १; ८८, ४; ८. २,
  ११; ८, ६; ८; ९; ९. २, १५; १०. ६,
  १६; ७, ७; ३६; ८, १८; ९, १०; १०,
  ३३; ११. १, १२; २१; २, २५; ७, २;
  २२; ८, २०; ११, २२; २४; १२,
  ९; १२; २३; २४; १२. २, ४६; ३, १५;
  ३६; ४०; ४, ३५; ३६; ९, ६; १३. २,
  १०; ३८; ३, १४; १४. २, ६९; १५.
  ६, २४; १४, २३; १८. २, ३४; ४, ७०;
  १९. २८, २; ५; ६; ७; ८; ९; १०; २९,
  १; २; ३; ४; ५; ६; ७; ८; ९; ३२, ६;
  ३४, २; ३५, ५; ३६, ३; ४; ५; ४६, २;
  ५; ४८, ५; ५०, ७; ५४, ५; २०. ११२,
  ३; १४३, ९.

सर्वाभिः १०. ६, २८; ११. ८, २०.

सर्वाभ्यः ४. ४०, ८; २०. २०, ७; ५७, १०.

सर्वासाम् ४. ८, ५; १७, ८; ५. १३, ८;
  २३, १३; ६. ८३, २; ९०, २; ७. ३६,
  २; १५. ६, २३.

सर्वै १. ७, ५; १९, ४; २. ३२, ५; ३. २२,
  १; ४. ६, ७; १६, ६; ५. ३, ३; ७, ६;
  ८, १; २१, ७; २३, १२; ६. ५५, १;
  ७३, १; ७. ४१, १; ५८, ७; ७८, ४;
  ८४, २; ८. ५, १०; १९; ७, २४; ९. १,
  २०; २, ७; १०; ४, १५; १०. ७, १३;
  २२; ८, १४[२]; १७; ९, ४; ७; ९; १०,
  २३; ११. १, ३३; ३, १९; ६, १२; १८;
  ७, २; ५; २२; २३; ९, ११; १३; २३;
  २४; २५; २६; २७; १०, १७; २५; २७;
  १२, १४; १५; १२. ३, ५१; ७, २; ३;
  १३. ५, ८; ६, ६; १४. १, ३३; १५.
  ६, २२; १९. ९, १२; १४; ४६, ४; २०.
  १३७, १.

सर्वैण ३. ३१, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ५. ३०, ६; १०. १०, १३; १५.
सर्वैभ्यः १. ३०, २; १५. ५, १४; १५; १९. २२, १८.
सर्वैषाम् ५. २३, १३; ६. ८५, २; ११६, ३; ९. १३, १०; ११; १२; १९; २०; १०. ४, २०; ११. ११, २६; १२. ४, २०; १५. ६, २३; १९. ३१, १.
सर्वैषु ६. ५८, २.
सर्वैः १. १५, ३; ४; ४. १४, ९; १६, ९; १०. १०, १४; ११. ११, ६; १७. १, २९; १९. ८, ४.
सर्षत् ४. ११, ३.
सऽर्लक्ष्मा १८. १, २; ३४.
सलिलः ५. १७, १.
सलिलम् ८. ९, २; १२. १, ८.
सलिलस्य ९. १५, ९; १०. ७, ३८; ११. ७, २६; १८. ४, ३६.
सलिलात् ४. १५, ११; ८. ९, १; ११. ६, २१.
सलिलानि ९. १५, २१; १०. ८, ४०.
सलिले १०. ७, ४१; १७. १, ८; १८. ३, ८.
सलिलेन १७. १, २९.
सवनम् ६. ४७, ३; २०. २२, ३; ९६, २.
सवनस्य ७. ७६, १.
सवना २०. १५, २; ५७, २; ६८, २; ७३, १.
सवनानि २०. ३१, १; १०४, ३.
सवने ६. ४७, २; ७. ८१, २; १०२, ४; ९. १, १२; १३; २०. १२, ५; ७; ७७, २; ९४, ९.
सवनेषु २०. १७, ६; २२, ४; ३५, ७; ७१, ९; ७२, १.
सवम् ७. ७७, ७; ९. १५, ४.
सऽर्वर्णाम् १८. २, ३३.
सऽवाचसः ७. १३, २.
सऽवासिनौ २. २९, ६.
सवासिनौऽइव ३. २९, ६.
सवितः ५. २५, १२; ७. १७, १.
सवितः २. २९, २; ४. ४, ६; २५, ६; ६. १९, ३; ९९, ३; ७. १५, ३; १६, १; १२०, २; १०. ८, ५; १४. १, ६२; १९. ८, ४.
सवितवे ६. १७, १; २; ३; ४.
सविता १. १८, २; ३; २६, २; २९, ३; ३३, १; २. २६, १; ३६, ८; ३. ८, २; ११, ४; १२, ४; १५, ६; ४. ८, ६; २५, ३; ४; ५; ५. ३, ९; २४, १; २६, २; २७, ३; ६. १, ३; ४०, १; २; ५३, १; ५८, १; ६१, १; ६८, १; ३; १०३, १; ७. १५, ४; १८, ४; २५, १; ३१, १; ७७, ६; ७; ८. १, १५; ३, १६; ५, ५; १०; १४, ३; ९. ४, १०; १०, १; १२, १०; २१; १५, ४; १०. ६, १३; ८, ४२; १३. १, २०; ३, १३; ४, १; १४. १, ९; १३; १९; ३३; ४७; ४९; ५०; ५१; ५३; ५८; २, १२; ३९; ५९; ६०; ६१; ६२; ७५; १८. १, ५; ३६; २, ५५; ३, १२; २९; ४, ३१; १९. १०, १०; १६, १; २०, १; २४, ८; २७, १४; ३१, १; ५; ४६, ७; २०. ९६, ९.
सविताऽईव १३. १, ३८; १९. ४५, ४.
सवितारम् ३. ८, ३; २०, ७; २१, ८; ४. २५, ७; ६. १, १; ७. १५, १; ११. ८, ३; १३. २, ३६; १९. २४, १.
सवितुः ४. २५, १; ६. २३, ३; ९. २, ६;

१०. ५, १४; ११. ४, १६; १२. २, ४८; १९. ४९, १; ५१, २.
सऽविद्युतम् ४. १५, १६.
सर्वीमनि ७. १५, २.
सवे ६. २३, ३.
सऽवेंदसः १२. २, १४.
सवेन ६. १९, ३; ९. २, ६.
सव्यः १५. १८, ३.
सव्यम् १२. १, ३४; १५. १८, २.
सव्यऽस्थाः ८. ८, २३.
सव्यात् ७. २७, ८.
सव्ये ७. ५२, ८.
सऽव्रंताः ३. ३०, ३.
सश्चत् २०. ९५, १.
सश्चिरे २०. १०९, ३.
ससताम्ऽईव २०. २१, १.
ससद्यात् ६. २९, ३.
ससन् ४. १, ६.
ससन्तु २०. ७४, ४.
ससऽवांसम् २०. ११, ८.
ससऽवान् १८. १, २२; २०. ७६, २.
ससहं १९. ३४, ५.
ससहानः २०. ७५, २.
ससहानःऽईव ३. ६, ४.
ससहानम् १७. १, १; २; ३; ४; ५.
ससहिः ३. १८, ५; १९. ५२, २; २०. १९, ६.
ससहिम् ३. २१, ३; २०. ६१, १; ९२, १९.
ससहे १. १६, ३; २. ५, ३; २०. १३७, ९.
ससह्याम २०. ७०, २०.
ससऽह्वांसम् २०. ४६, १.
ससाद ५. १, २.
ससान २०. ११, ८; ९.
ससान २०. ११, ९^{३},
सऽस्नुः ५. २७, १.
ससूव १०. १०, २३.
ससूव २०. १२६, २३.
ससृजे १०. ७, ८; १९. ९, ३; ४; ५.
ससृजे २. २९, ७.
ससृज्महे २०. ५६, ५; १००, १.
ससृज्रिरे २०. २२, ५.
ससृज्रिरे २०. ९२, २.
सस्ताम् २०. ७४, ३.
सस्नि ५. २, २; २०. १०७, ५.
सस्यम् ७. १२, १; ८. १३, ११; १२.
सस्रुतः ६. ६७, १.
सस्रुषीः ६. २३, १^{२}.
सस्वजाते इति ९. १४, २०.
सह १. १, २; ४, २; २. ७, ५; १०, २^{२}; ३०, ५; ३६, १; ३. ४, १; ५, ३; १२, ७; ९; १३, ५; ३०, ६^{२}; ४. २१, ३; ३१, ६; ३८, ५; ६; ७; ५. ६, ११; १२; १३; १४; २१, ८; २२, १०; १२^{२}; २९, २; ३; ३०, ६; ६. ५९, २; ६४, २; ११९, २^{२}; १३२, १; २; ३; ४; ५; ७. ३७, १; ६२, ७; ६७, ३; ८७, २; ९४, २; ११०, १; ८. १, १; ११; ८, २१; ९. १, १५; ३, १४; २३; १०. ५, ४७; ६, २; २२; २३^{२}; २४^{२}; २५; २६^{२}; २७^{२}; २८; ३०; ७, ५; १०, १३; २५; ११. १, १; ७; २२^{२}; ७, २०; ८, १९; २०; ९, ८; ११; २०; २४; १०, ३०; ११, ५; १२, १; २; ५; ६; १२. १, ३९; ५९; ३, १०; १५; १७; ३२; ३९^{२}; ५५; ५६; ५७; ५८; ५९; ६०; ४, २४; १३. १, १५; ३, ५; ६, ७; १४. १, ४८; २,

१[२]; २; १७. १, २४; १८. २, ५९; ६०; ३, ५६; १९. ६, ४; ८, २; ११, २; १७, ९; ३०, ५; ३१, ७; ९; ३६, १; ४०, १; ४३, १; २; ३; ४; ५; ६; ७; ८; ५८, ६; २०. १७, ९; ४२, ३; ६३, १; ९६, १२; १२४, ४.
सहः २. १७, २[२]; ३. ५, ४; ४. ३१, ६; ३२, १; ३६, ८; ६. ४, १; १२५, २; ८. ७, ५; १०. ५, १; २; ३; ४; ५; ६; ११. ८, १५; ९, १३; १२. ६, १; १३. ४, १२; ५, ७; ८, ५; ६; १८. ४, ५३; १९. ३७, १; २; ५२, २; २०. १५, ६; ६१, ५; ६२, ९; ६७, ६; १०९, ३; १४१, ३.
सहःऽकृतः २०. १०४, २.
सहःऽकृतम् ६. ३९, १.
सहःऽकृतेन ४. ३२, १.
सहःऽजित् १९. १३, ५.
सहःऽजित्तम् १७. १, १; २; ३; ४; ५.
सहःऽदाम् २०. ११, ८.
सहःऽभिः ७. २६, १; २.
सहःऽवानम् ७. ९०, १.
सहऽकण्ठिका १०. ९, १५.
सहऽचारम् २. २६, १.
सहऽजाः ४. ३१, ६.
सहताम् ८. ६, ७.
सहते १. १६, ३; २. ४, ३; ५. १७, १८; ८. ३, २४; १३. २, ३१; १८. १, ४८; २०. १७, ६.
सहऽदेवता १२. ४, २३.
सहध्वम् ३. १, २.
सहध्वम् १९. १३, ३.
सहन् २०. ९०, २.
सहन्ते १. ३५, २.
सहऽपत्न्यै १४. १, ५८.
सहऽपुरुषान् ६. ५६, १.
सहऽभक्षाः ६. ४७, १.
सहऽभूते ४. ३१, ६.
सहमानः ३. ६, ४; ५. २०, ११; ८. ५, २; १२. १, ५४; २, ४६; १३. २, २८; १९. १३, ५; ३२, ५.
सहमानम् ७. ६५, १; १७. १, १[२]; २[२]; ३[२]; ४[२]; ५[२].
सहमाना २. २५, २; २७, १; ३. १८, ५.
सहमानाः ८. ७, ५.
सहमानाम् ३. १८, ६; ४. १७, २; ८. २, ६.
सहऽमूरान् ५. २९, ११; ८. ३, १८.
सहऽवीरम् २. ६, ५; ३. १२, ५.
सहऽशेय्याय १८. १, ८.
सहऽसंभलायै १४. १, १९.
सहसः ९. ५, १३; १८. १, २४; २०. ६७, ३; ९३, ५.
सहसः २०. १०३, ३.
सहसा २. २९, ३; ४. ३२, १; ३६, ३; ४; ५. २०, ३; ६. ७२, १; ७. ३६, १; १९. १३, ७; ५२, २; २०. ८८, १.
सहसाऽवन् २०. ३७, ७.
सहऽसूक्तवाकः ७. १०२, ६.
सहसे ८. ४, ३; १९. ३७, ३; २०. ८७, ३.
सहस्य ७. ७४, १; ८. ३, २२.
सहस्येनि ४. ५, १.
सहस्रऽअक्षः ४. २०, ४; ६. २६, ३; ३७, १; १०. ३, ३; १९. ६, १; ५३, १.
सहस्रऽअक्षम् ९. ३, ८; ११. २, १७.
सहस्रऽअक्षरम् १०. ८, ७; ११. ६, २२.

सहस्रऽअक्षरा ९. १५, २१; १३. १, ४२.
सहस्रऽअक्षाः ४. १६, ४.
सहस्रऽअक्षाय ११. २, ३.
सहस्रऽअक्षेण ३. ११, ३; ११. २, ७; २०. ९६, ८.
सहस्रऽअक्षौ ४. २८, ३.
सहस्रऽअर्घः १९. ३३, १.
सहस्रऽअर्घम् १८. १, ४३; ४, ४७.
सहस्रऽअर्घस्य ८. ८, ७.
सहस्रऽअह्नयम् १०. ८, १८; १३. २, ३८; ३, १४.
सहस्रऽआयुः १७. १, २७.
सहस्रऽऋष्टिः १९. ६६, १.
सहस्रऽकाण्डेन २. ७, ३; १९. ३२, ३.
सहस्रऽकुणपा ११. १२, २५.
सहस्रऽघ्नि ११. २, १२.
सहस्रचक्षो इति सहस्रऽचक्षो ४. २०, ५; १९. ३५, ३.
सहस्रऽदक्षिणाः १८. २, १७.
सहस्रऽधा १०. ७, ९.
सहस्रऽधामन् ४. १८, ४.
सहस्रऽधारः २०. १३७, ६.
सहस्रऽधारम् ३. २४, ४[२]; १७. १, १५; १८. ४, ३६.
सहस्रऽधाराम् ७. १६, १; १०. १०, ४.
सहस्रऽधारे ५. ६, ३.
सहस्रऽधारौ ९. १, ७.
सहस्रऽनाम्नीः ८. ७, ८.
सहस्रऽनीथाः १८. २, १८.
सहस्रऽपर्णः १९. ३२, १.
सहस्रऽपर्ण्यः ८. ७, १३.
सहस्रऽपर्ण्या ६. १३९, १.
सहस्रऽपात् ७. ४२, २; १९. ६, १.
सहस्रऽपादम् २०. ९२, १३.
सहस्रऽपृष्ठः ११. १, १९; २०.
सहस्रऽपोषम् ७. ५०, २.
सहस्रऽपोषस्य ३. ७९, ३.
सहस्रऽपोषाय ६. १४१, ३.
सहस्रऽप्रधनेषु २०. ७०, १०.
सहस्रऽप्राणः १९. ४६, ६.
सहस्रऽबाहुः १९. ६, १.
सहस्रम् १. १०, २; २. ९, ३; ५. १५, ११; १८, १०; ६. ४४, २; ६३, ३; ७७, ३; ७८, ३; ८४, ४; ७. २३, १; ३६, २; ४५, १; ८. ८, ७; ९. ४, ९; ५, १७; १०. ८, २४; १०, ९; १२. १, ४५; १३. १, ३७; १७. १, ३०; १८. ३, ४७; ५१; १९. ३०, २; ४६, ५; २०. ८१, १; ९२, २०; १०४, २; १४३, ९.
सहस्रऽमूलः १३. ३, १५.
सहस्रऽवर्चसा ६. ७८, २.
सहस्रऽवीर्य १९. ४४, ८; ९.
सहस्रऽवीर्यः २. ४, २.
सहस्रऽवीर्यम् ४. १७, १; ६. ३९, १; ८. ५, १४.
सहस्रऽवीर्येण ८. १, १८.
सहस्रऽशः ३. २४, १; ८. ८, १; १६; ११. ११, २३.
सहस्रऽशृङ्गः ४. ५, १; १३. १, १२.
सहस्रऽशोकाः २०. ३०, ४.
सहस्रऽसातमम् २०. ७१, १४.
सहस्रऽसातमा ३. २८, ४.
सहस्रऽस्तुका ७. ४८, ३.
सहस्रस्य १. १७, ३.
सहस्रऽहः ८. ८, १७.

सहस्र॑ऽहस्त ३. २४, ५.
स॒हस्रा॑ २०. २१, ९; ६७, १; ७३, ६.
स॒हस्रा॑णि २०. २१, ६.
स॒ह॒स्रिण॑म् २०. ९, २; ४९, ५; ५२, ३; ५७, १६; ६९, ७.
स॒ह॒स्रिणी॑भिः २०. ३६, २.
स॒हस्रे॑ण ४. १९, ८.
स॒हस्रे॑णऽइव २०. ५१, १; ३.
स॒हस्रे॑षु २०. ७४, १; २; ३; ४; ५; ६; ७.
स॒हस्रैः॑ २०. १३७, ७.
सह॑स्व २. २५, ३; ३. ६, ६; ४. ३१, ३; ३७, १०; ७. ३६, १; १९. ३२, ६^{३}.
स॒ह॒स्व॒ ४. ३१, २; ५. १४, ८; १९. ३१, ११; ४६, २.
सह॑स्वत् ४. २७, ७; २०. ४०, २; ७०, ४.
सह॑स्वतः ४. ३३, ५.
सह॑स्वता ४. ३२, १.
सह॑स्वति ३. १८, २.
सह॑स्वती॒ इति॑ ३. १८, ५.
सह॑स्वतीम् २. २५, १; ८. २, ६.
सह॑स्वन्तौ १९. ३२, ५.
सह॑स्वान् २. ४, ६; ८. ५, २; ९. २, १५; ११. १, ६; १९. १३, ५; ३२, ५; १०; ३४, ४; २०. ३६, १.
सहां॑सि २०. ९४, १.
स॒हा॒म॒हे॒ २. ४, ४; ४. १०, २.
स॒हा॒व॒है॒ ३. १८, ५.
स॒हि॒षी॒म॒हि॒ ३. ६, ४; १९. ३२, ५.
सही॑यसी १०. ५, ४३.
सही॑यसीः ८. ७, ११.
सही॑यसीम् ३. १८, ६.
सही॑यांसम् १७. १, १; २; ३; ४; ५.
सही॑यान् ४. ३२, ४; ५. २०, १०; २०. ३५, ७.
स॒हु॑रिः ४. ३२, ४.
स॒हु॒रे॒ ४. ३१, २; ५; ३२, ६.
स॒ऽहृद॑यम् ३. ३०, १.
सहे॑ ४. ३६, ४.
स॒हे॒ ४. ३६, ३; १९. ६१, १.
स॒ह्याम॑ ४. ३२, १.
सा १. १३, ४; १४, २; २४, ३; २८, ३; ३४, १; २. २९, ७; ३. १०, १^{२}; २; ३; ४; ८; १७, ४; ९; १८, ४; २२, ४; २८, १; ५; ६; ४. १७, ३; २०, ३; ३८, ३^{२}; ३९, २; ४; ६; ५. ५, १; ४; ५; ९^{२}; १४, १२; १७, ४; १८, ३; ९; १५; १९, ४; ७; ६. १५, २; ३८, १; २; ३; ४; ५९, ३; १००, ३^{२}; १२४, ३; १३३, ४; ५; ७. ७, २; २१, ५; ४९, १; ५८, २; ७७, ८; ८. ४, १७; ९, ८; ११; १०, २^{२}; ४^{२}; ६^{२}; ८^{२}; १०^{२}; १२^{२}; ११, १^{२}; १२, १^{३}; ३^{३}; ५^{३}; ७^{३}; १३, १^{२}; ५^{२}; ९^{२}; १३^{२}; १४, १^{२}; ५^{२}; ९^{२}; १३^{२}; ९. १, २०; २, ५; १४, ८; १७; १५, ५; ७; २१; १०. १, १; २; २४; ५, ३७^{२}; ८, १०; २५; ३०; ९, ८; ९; २५; १०, २८; ११. १, २४; १०, १७; १२. १, १; ३; ४; ७; ८; ९; १०; १३; १८; २२; २६; ४०; ४१; ५२; ३, ११; ४, ३५; ७, १; ४; ५^{३}; १३. १, ४१; ४२; १४. १, ६०; २, ६; १४; ५०; ७०; ७१; १५. १६, १; २; ३; ४; ५; १७, १; ३; १६. ७, ४; १८. १, ४; २, ५२; ४, ८८; १९. ४, २; १९, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; ४८, ४^{३}; ६; ४९, २; ५५, २; २०. ९७, २; १४३, ७.

साकम् १. १०, २; ११, ६; १७, ३; ४. १, ६; २८, ४; ५. २८, ८; ६. ६१, २; १२९, १; ७. १२०, ३; १०. ८, ९; ११. १, ७; ७, ५; २३; १०, ३; १२. २, १; २५; १३. ३, १०; १४. २, ४१; ४२; १८. ४, ६; १९. ७, १; १२, २; २९, ५; ६; ७; ८; २०. ९१, ५; १२६, १४; २३; १४२, १.
साकम्ऽजानाम् ९. १४, १६.
साक्षाम २०. ८७, ४.
साक्षीय १९. ३२, १०.
साक्षे २. २७, ५.
साक्ष्वं २०. १९, ७.
साढः ५. ३०, ९.
सातऽघ्नः ३. १५, ५.
सातये २०. ६८, ९; ११८, ३.
साता २०. ७२, २; ७५, १; ९८, १.
सातिम् २०. ७०, ६.
सात्मऽत्वाय ९. ८, ८.
सात्राऽसहस्य ५. १३, ६.
सादय ११. १, २३.
सादयति ९. ७, ३.
सादयाथः १२. ३, ५२.
सादयामि ६. १२२, ५; १०. ९, २७; ११. १, २७; १४. २, ४९; १८. ४, ६७.
सादयित्वा १२. २, २०; १४. २, ६७.
सादये १०. ५, ७; ८; ९; १०; ११; १२; १३; १४.
सादिनः ११. १२, २४.
साधन् २०. ७७, ३.
साधनम् २०. १३८, ३.
साधय १. २४, ४.
साधु ११. १, ९; १८. ४, ३.
साधुऽअर्याः २०. १६, ३.
साधुः १६. ६, ११.
साधुऽदेविनीम् ४. ३८, १; २.
साधुना १८. २, ११.
साधुऽया १०. ४, २१.
साध्याः ७. ५, १; ८४, २; ८. ८, १२; १०. १०, ३०; ३१; १९. ६, ११.
साध्यानाम् ९. १५, २४.
सानसिम् २०. १४, २; ६२, २; ७०, १७.
सानुषु १०. ४, १४.
सानौ ११. ७, १२.
सापत्नः २. ७, २.
साम ७. ५६, १; ५७, १; ९. १५, २; १०. ७, १४; ८, ४१; ११. ९, ५; १०, २३; १४. २, ७१; १५. ३, ८; २०. ६२, ५.
सामऽगेभिः २. १२, ४.
सामऽतेजाः १०. ५, ३०.
सामनौ १४. १, ११.
सामऽसाम ८. ९, १६.
सामानि ८. ९, ४; १६; ९. ६, २; १०. ७, २०; ४४; १०, १४; ११. ८, १४; ९, २४; १५. ६, ८; १९. ६, १३.
सामऽइत्यः ८. १०, ११.
साम्ऽइत्यै १३. १, १३.
सांग्रामऽजित्याय ५. २०, ११.
साम्ऽतपनस्य ६. ७६, २.
साम्ऽतपनाः ७. ८२, १.
साम्ऽतपनाः ७. ८२, ३.
साम्नः ११. ९, ५.
साम्ना १०. ८, ४१; ११. ३, १५; १२. १, ३८.
साम्नाम् १५. ६, ९.
साम्ऽमनस्यम् ३. ३०, १.
साम्ऽराज्यम् १४. १, ४३.

सायक ४. ३१, ६; ३२, १.
सायकऽप्रनुत्तानाम् ९. २, १२.
सायकम् २. ५, ७; २०. १०९, २.
सायम् ३. १२, ३; ४. ११, १२; ६. १०८, ५; १२८, २; ४; ८. ६, १०; ११. २, १६; १३. ३, १३; १८. ४, ६५.
सायम्ऽप्रातः ३. ३०, ७; १९. ३९, २; ३; ४.
सायम्ऽभवम् १०. २, १६.
सायम्ऽसायम् १९. ५५, ३; ४.
सारघेण ६. ६९, २; ९. १, १९.
सारङ्गम् २. ३२, २; ५. २३, ९.
सारथिः ८. ८, २३; १५. २, ७; १४; २०; २७.
सारमेयौ १८. २, ११.
सारा ४. ४, ४.
सालावृकान्ऽइव २. २७, ५.
सावित्री १४. २, ३०.
सावित्रीम् ६. ८२, २.
साविषक् १. १८, २.
साविषत् ६. १, ३; ७. ७७, ७; ९. १५, ४.
सावीः ७. १५, ३.
साहन्त्य ६. ७, २.
साहस्रः ९. ४, १; ७.
साहस्रम् १८. ४, ३५.
साहस्रे ९. ४, २.
साह्नऽअतिरात्रौ ११. ९, १२.
सिंहः ८. ५, १२.
सिंहःऽइव ५. २०, १; २.
सिंहऽप्रतीकः ४. २२, ७.
सिंहम् ४. ८, ७.
सिंहम्ऽइव ४. ३६, ६; २०. ९१, ९.
सिंहस्य ५. २१, ६; १९. ४९, ४.
सिंहस्यऽइव ८. ७, १५.
सिंहाः १२. १, ४९.
सिंहे ६. ३८, १.
सिकताः ७. ११४, २; ११. ३, १२; ९, २१.
सिकताऽवती १. १७, ४.
सिचः ११. ११, १८; १२, २०; १४. २, ५१.
सिचा १८. २, ५०; ३, ५०.
सिच्यते ५. १९, ६; ६. ११, २; १०. ८, २९; २०. १३९, ४.
सिच्यमानायाम् ६. ६९, १; ९. १, १८.
सिञ्च २०. ६४, ४.
सिञ्च ४. १५, १६; ७. ७७, ६; ९. ५, ५; १२. ३, ४५; १९. ३१, १२.
सिञ्चत ६. ५७, २[२].
सिञ्चतम् ३. १७, ७.
सिञ्चति ११. ७, १२.
सिञ्चतु ५. २५, ५.
सिञ्चथ ६. २२, २.
सिञ्चन्तु ७. ३४, १[२].
सिञ्चात् २०. १४०, २.
सिञ्चामि २. २६, ४; ३. २२, ६; ४. ८, ५; ६. १३६, ३; २०. ४, २.
सिञ्चेत् १६. १, ९.
सिताः ८. ८, १०.
सिनातु ३. ६, ५.
सिनामि ६. १३३, ३.
सिनीवालि ७. ४८, १; १४. २, १५; २१.
सिनीवालि ५. २५, ३.
सिनीवाली २. २६, २; ६. ११, ३; १९. ३१, १०.
सिनीवाल्याः ९. ४, १४.
सिनीवाल्यै ७. ४८, २.
सिन्धवः १. १५, १; ४. ३, १; ६, २; २४,

२; १०. ४, २०; १९. १०, ८; २०. १७, ३; ३५, ११; ९२, ९; १०७, १.
सिन्धवः ३. १३, १; ६. ३, १.
सिन्धुः १२. १, ३; १४. १, ४३.
सिन्धुतः ४. १०, ४; ७. ४६, १.
सिन्धुऽपत्नीः ६. २४, ३.
सिन्धुऽभ्यः १. ४, ३.
सिन्धुम् ९. १५, ३; २०. १७, ७; २५, १; ६३, ९.
सिन्धुम्ऽइव ४. ३३, ८.
सिन्धुऽराज्ञीः ६. २४, ३.
सिन्धुऽसृत्याय १०. २, ११.
सिन्धून् ६. ६१, ३; १२. ३, ५०; २०. ३४, ३; १३; ९१, १२; ९५, ३.
सिन्धूनाम् १८. ४, ५८.
सिन्धोः ४. १३, २; १०. ४, १९; १८. ३, १८; १९. ४४, ५.
सिन्धौ ६. १, २; २४, १.
सिमं २०. १२०, १.
सिमसै २०. १२३, १.
सिलाची ५. ५, १; ८.
सिलाञ्जाला ६. १६, ४.
सिसासति १३. २, १४; २०. ६७, १.
सिसासथ ६. २१, ३.
सिसासन् २०. ९०, ३.
सिसासवः ६. २१, ३.
सिसिचे २०. ८, ३.
सिस्यदुः ९. २, २०.
सिस्यदे ५. ५, ९.
सिस्रताम् १. ११, १.
सिस्रते १३. २, ४६.
सीता ३. १७, ९.
सीताः ११. ३, १२.
सीताम् ३. १७, ४.
सीते ३. १७, ८.
सीते ३. १७, ९.
सीद ११. १, २९^{२}; ३५; १२. ३, ३३; १४. २, २४; २५; १९. ६१, १; २०. २३, ३.
सीदत् १८. १, २९.
सीदत २०. १३, २.
सीदत ११. १, १२; २०. ६८, ११.
सीदतः १२. ३, ३०.
सीदताम् १८. ३, ३८.
सीदतु १८. ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.
सीदन्तु ४. २१, १.
सीदन्तु ११. १, २५.
सीदसि १९. ३३, ३; २०. ११३, २.
सीदामि ३. १२, ९; ९. ३, २३.
सीदेम १२. १, २९.
सीम् २०. २२, ६; ३५, ११; ७८, २; ९२, ३.
सीमतः ४. १, १; ५. ६, १.
सीमन्तम् ६. १३४, ३.
सीमानम् ९. १३, १३.
सीरऽपतिः ६. ३०, १.
सीरम् ८. ९, १६.
सीरा ३. १७, १; २.
सीवयामि ६. ७३, २.
सीव्यन्तु ७. ५०, १.
सीव्यध्वम् १९. ५८, ४.
सीषती ४. ३८, ३.
सीसधाम २०. ६३, १; १२४, ४.
सीसम् १. १६, २; १२. २, १; ५३.
सीसाय १. १६, २^{२}.
सीसे १२. २, १९; २०.

सीसेन १. १६, ४.
सु १. २, १; १७, ४; २४, ४; ५. १, ५; २, ३; ६, ४; ५; ६; ७; ११, ७; ६. ३२, १; ८४, ३; ७. ६, २; ७५, २; ७७, ७; ९०, १; ९. १५, ४; १४. २, ९; १८. १, १६; ३७; ३, ५१; ६०; ६२; १९. २४, ५; २०. ४, १; १७, २; १९, २; ५१, ३; ६०, ३; ६७, २; ७१, १२; ८०, २; ८९, १; ९४, ९; ९५, २; ४; १०७, ६; ११६, २; ११७, ३; ११८, १; १२४, ३.
सुऽअङ्कुरिः ७. ४८, २.
सुऽअङ्कुरे २०. १२६, ८.
सुऽअध्वरः १८. १, २२; २०. ६७, ३.
सुऽअपत्याय २०. २५, ६.
सुऽअपसः ५. १२, ८; १८. ३, २४.
सुऽअपस्यते १८. १, २३.
सुऽअपायति १९. ४९, १०.
सुऽअरंकृता १०. १, २५.
सुऽअरिः २०. ३५, ९.
सुऽअरित्राम् ७. ७, १.
सुऽअर्काः ७. २५, १; ८२, ३; १९. १०, ९.
सुऽअर्कात् २०. २, १; २; ३; ४.
सुऽअर्थी ५. २०, ७.
सुऽअष्ट्रान् २०. ८९, ५.
सुऽअस्तकौ १४. १, २२; २, ६४.
सुऽआक्तम् ७. ३१, १[४].
सुऽआभुवः २०. १३, १.
सुऽआयसाः १०. १, २०.
सुऽआदध्यः १९. ५०, २.
सुऽआशिर्षम् २०. ९४, ५.
सुऽआसत् १६. ४, २.
सुऽइते ६. ५५, २.
सुऽइष्ट्ये ५. २७, ९.
सुऽइष्टिम् २. ३५, १; ६. ४७, ३.
सुऽउपसर्पणा १८. ३, ५०.
सुऽउपायना १८. ३, ५०.
सुऽउषाः १६. ४, २.
सुऽओजः २०. ३६, ६.
सुऽओजाः २०. ७६, ८.
सुऽकर्माणः १८. ३, २२.
सुऽकल्पम् १२. २, ५.
सुऽकिंशुकम् १४. १, ६१.
सुऽकृत् ५. २७, ३.
सुऽकृतः १७. १, २७.
सुऽकृतः ३. २८, ५; ४. २४, १; ६. १२०, ३; ७. ८४, २; ८५, ४; १२. ३, ९; १८. १, ४१; २, ५५; ३, २०; ४, ३; ७; ४५; १९. ११, १; ५६, ५.
सुऽकृतम् १२. ३, ३३; २०. ९४, ९.
सुऽकृतम् ७. ४९, १.
सुऽकृतस्य २. १०, ७; ४. ११, ४; ६; १४, ६; ६. ११९, १; १२०, १; १२१, १; २; ७. ८८, ४; ९. ५, १९; ११. १, ८; १९; ३७[२]; १४. १, १९; १६. ९, २; १८. ३, ५४.
सुऽकृता २०. ११, ६.
सुऽकृतानि १९. १०, ४.
सुऽकृताम् ३. २८, ६; ६. १२४, १; ९. ५, १; ५; ८; ९; १२; ११. १, १७; १८; ३५; १८. २, ८; ३, ७१; ४, १; ११; ४४; १९. १०, ४.
सुऽकृते १८. ४, १४.
सुऽकृते १४. १, ५९.
सुऽकृतैः ११. १, ३६.
सुऽकृतौ १२. ३, ४४.

सुऽकृत्यया २०. २५, ४.
सुकेषु १. २२, ४.
सुऽक्रतुः ७. १५, २.
सुऽक्रतुम् २०. १०१, १.
सुक्रतो इति सुऽक्रतो २०. ६९, ४.
सुऽक्षतस्य ७. ८०, ४.
सुऽक्षयम् २०. ७३, ५.
सुऽक्षेत्रतायै ७. २१, ५.
सुऽक्षेत्रिया ४. ३३, २.
सुऽखः ५. १४, ५; १३; १९. ७, ३.
सुऽखम् ८. १, ६; १३. १, २४; २, ७; २०. ८६, १.
सुऽखे २०. २३, ९.
सुऽगम् ३. ३, ४; ७. ५२, ४; ८. ४, ७; १४. १, ५८; २, ६; ८; २०. १२६, ५.
सुऽगा ७. १०२, ४.
सुऽगार्तवे ६. १, ३.
सुऽगातुया ४. ३३, २.
सुऽगार्हपत्यः १२. २, ४५.
सुगू इति सुऽगू १४. २, ४३.
सुऽगृहौ १४. २, ४३.
सुऽगेन १४. २, ११.
सुऽगोपातमः २०. १, २.
सुऽचक्रः ४. १२, ६.
सुऽचक्रम् १४. १, ६१.
सुऽचित्राम् ७. १६, १.
सुऽजनिमा १२. २, २४.
सुऽजन्मा ५. १, १.
सुऽजातता १९. १२, १.
सुऽजातम् २. १३, ५; ४. २३, ४; ७. २१, ५.
सुऽजाते १९. ४९, ३.
सुऽजिह्व ५. १२, २.
सुऽज्यैष्ठ्यः १४. २, २४.
सुतः २०. ५, ६; ८, २; ६७, ६.
सुऽतर्पसौ ४. २६, ३.
सुतऽपाव्ने २०. ६९, ३.
सुतऽपेयाय २०. १४३, ३.
सुतऽपौ ७. ६०, १.
सुतम् ४. २९, २; ७. ६०, १; २०. ६, २; ५; ६; ७, ४; २२, १; २४, १; २; ७; ४२, ३; ५२, २; ५७, १५; ९५, १; ९७, १; ११०, १.
सुतऽवतः २०. ४, १; ८४, २.
सुतऽवन्तः २०. ३, ३; ३८, ३; ४७, ९; ५२, १; ५७, १४.
सुतऽवान् २०. ६३, ६.
सुतऽसोमम् २०. ८७, १.
सुतऽसोमस्य २०. ३४, ६.
सुतस्य २. ५, १; २; ७; १८. १, ४५; २०. २४, ९; २५, ७; ३३, १; २; ६०, ३; ६९, ४; ९९, २.
सुताः २०. ६, ४; २४, ५; ५१, ४; ६९, ३; ८४, १; ९६, २.
सुतानाम् २०. ३२, ३; ९३, ३.
सुतासः २. ५, ४; २०. ७६, ६; ९६, १; १३७, ४.
सुऽतुका २०. ३६, १०.
सुऽतुकान् २०. ८९, ५.
सुते २०. १, १; ६, १; २२, १; ५२, २; ५३, १; २; ५६, ५; ५७, ११; १२; १५; ६८, १२; ७१, ८; ७३, ५; ७८, १; ८४, ३; ८५, १; ९४, ९; ११०, [illegible]; १११, २.
सुऽतेजसा ८. २, १७.
सुतेऽसुते २०. ७१, १६.

सु॒ऽत्रामा॑ ७. ९६, १; ९७, १; १८. ३, ६१; २०. १२५, ६; ७.
सु॒ऽत्रामा॑णम् ७. ७, १.
सु॒ऽत्रात्रे॑ १९. ४२, ३.
सु॒ऽदक्ष॑म् २०. ७७, १.
सु॒ऽदत्रः॑ ७. ११, १.
सु॒ऽदान॑वः ४. १५, २; ७; ९; ६. ३०, १; १४. २, ७२.
सु॒ऽदा॒न॒व॒ः १३. १, ३.
सु॒ऽदानु॑ ७. २१, ४.
सु॒ऽदानुः॑ १८. ३, ६१.
सु॒ऽदानु॑म् २०. ९, २; ४९, ५.
सु॒ऽदास॑म् २०. ३७, ३.
सु॒ऽदासे॑ २०. ३७, ६.
सु॒ऽदिने॑ १७. १, १७.
सु॒ऽदि॒वम् १९. ८, ३.
सु॒ऽदी॒तयः॑ २०. ५४, ३.
सु॒ऽदी॒तये॑ २०. १०३, १.
सु॒ऽदुघा॑ १२. ४, ३५; १८. ४, ५०; २०. १७, ९.
सु॒ऽदुघाः॑ २०. ९२, ७.
सु॒ऽदुघा॑म् ७. ७७, ७; १०९, १; ९. ४, २१; १५, ४.
सु॒दुघा॑म्ऽइव २०. ५७, १; ६८, १.
सु॒ऽदृढ॑म् १०. २, ३.
सु॒ऽदृशी॑कम् २०. ७७, ४.
सु॒ऽदे॒वः २०. ९२, ९.
सु॒ऽधाया॑म् १७. १, ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २१.
सु॒ऽधि॑तम् २०. ५९, ४; ९२, १४.
सु॒ऽधृ॑तः १३. २, १२.
सु॒ऽनक्ष॑त्रम् १९. ७, ३.
सु॒ऽना॒था॒ः १२. ३, २७.
सु॒ऽनाभिः॑ ४. १२, ६.
सु॒ऽनामा॑ ८. ६, ४[२].
सु॒नोत॑ ६. २, १; ३.
सु॒नोति॑ २०. ९६, ३; ४; १२६, १५.
सु॒न्व॒तः ११. १, ३०; २०. ५०, २; ६४, २; ६८, १०; १११, ३.
सु॒न्व॒ति २०. ५५, ३.
सु॒न्व॒ते ४. ३०, ६; ६. ६, १; ५४, ३; ७. ११५, ३; २०. ५, ४; १७, ८; २५, ३; २७, ३; ३४, १८; ५१, ३; ५६, २; ८९, ८.
सु॒न्वन् २०. ६७, १.
सु॒न्वन्त॑म् २०. १८, ३; ३४, १५.
सु॒न्वा॒नः २०. ६७, १[२].
सु॒न्वा॒नाय॑ २०. ६७, १.
सु॒न्वि॒रे २०. ११२, ३.
सु॒ऽप॑क्वे ५. २९, ६.
सु॒ऽप॒क्ष्म॑म् १३. २, २.
सु॒ऽपत्नी॑ ११. १, १४.
सु॒ऽपत्नीः॑ १२. २, ३१; १८. ३, ५७.
सु॒ऽपथा॑ २०. ५५, १; ९४, २.
सु॒ऽप॒र्णः १. २४, १; २. २७, २; ४. ६, ३; ५. १४, १; ६. ८, २; ८३, १; ७. ४२, २; ९. १५, २८; १२. ३, ३८; १३. २, ९; ३२; १८. ४, ८९; १९. ६५, १.
सु॒ऽप॒र्णम् ४. १४, ६; ७. ४०, १; १३. २, ३६; ३७; १८. ३, ६६.
सु॒प॒र्णऽया॑तुम् ८. ४, २२.
सु॒प॒र्ण॒ऽसु॒वने॑ ५. ४, २.
सु॒ऽप॒र्णस्य॑ ४. २०, ३.
सु॒ऽप॒र्णा ९. १४, २०.
सु॒ऽप॒र्णाः २. ३०, ३; ५. २८, ८; ६. २२,

१; ४९, ३; ८. ७, २४; ९, १७; ९. १४, २१; २२; १५, २२; ११. २, २४; १२. १, ५१; १३. ३, ९; १८. ४, ४.
सुऽपर्णैः ११. १२, २६.
सुऽपलाशम् २०. १७, ४.
सुऽपविः ४. १२, ६.
सुऽपारः २०. ६८, १०.
सुऽपाशया ३. ११, ८.
सुऽपिप्पलाः ३. १७, ५.
सुऽपुत्रा १४. १, १८.
सुऽपुत्रे २०. १२६, १३.
सुऽपुत्रौ १४. २, ४३.
सुऽपुना १२. २, ११.
सुऽपुष्टिम् १९. ७, ४.
सुऽपूर्णा ३. १०, ७.
सुऽपेशसः ७. ५०, २.
सुऽपेशसम् २०. ५९, ४.
सुप्तः १६. ७, १०.
सुप्तम् ११. ६, २५.
सुप्तान् ७. ११३, २.
सुप्तानाम् ७. १४, २.
सुप्तेषु ११. ६, २५[२].
सुप्त्वा १०. ३, ६.
सुप्रऽअवीः २०. २५, १.
सुप्रऽअव्या ४. ३०, ६.
सुऽप्रकेतम् २०. ८८, २.
सुऽप्रजसः ३. १०, ५; १८. ४, ६३.
सुऽप्रजसम् १४. १, ४९.
सुऽप्रजाः ४. ११, ३; १४. २, २२; २३; ७४; २०. ८८, ६.
सुऽप्रतिस्थितम् १२. १, ६३.
सुऽप्रतीकः ५. २७, १.
सुऽप्रतीकम् ४. २१, ६.
सुऽप्रतीकाः १०. ५, २४.
सुऽप्रनीतयः १८. ३, ४४.
सुऽप्रनीताः १९. ४, ४.
सुऽप्रनीतिम् ७. ६, २; ७, १.
सुऽप्रनीते ५. ११, ५; ७. २१, ४.
सुऽप्रपानम् १४. २, ६.
सुऽप्रपाने ४. २१, ७; ७. ७९, १.
सुऽप्रशस्तिम् ५. ११, ११.
सुऽप्रातः १९. ८, ३.
सुऽप्रायनाः ५. १२, ५.
सुऽप्रिया ७. ३९, २.
सुऽफला ३. १७, ८.
सुऽफालाः ३. १७, ५.
सुऽबद्धाम् १४. १, १८.
सुऽबन्धुम् १४. १, १७.
सुऽबाहुः ७. ४८, २; २०. ५, २.
सुबाहो इति सुऽबाहो २०. १२६, ८.
सुऽबुधा १४. २, ३१; ७५.
सुऽब्राह्मणाः ११. १, २६.
सुभगम्ऽकरणी ६. १३९, १.
सुऽभगा २. ३६, ३; ५. ७, १०; ६. ३, २; ३८, १; २; ३; ४; ७. ५०, १; १०. ९, ११; १४. १, १८.
सुऽभगाः ७. ६२, ६.
सुऽभगान् २०. ६८, ६.
सुऽभगाम् २. ३६, ३; ६. ५९, ३; १४. १, ४९; १९. ४, २; २०. १२६, ११.
सुऽभगे ३. १८, २; ५. ५, ६; ७; ६. ३०, ३; १९. ४९, ३.
सुऽभगे ३. १७, ८; ७. २१, ४; ५०, २; ८४, १; १८. १, ११; १३; १९. ४९, ५; ५०, ६.
सुभगे इति सुऽभगे ३. ७, ४.

सुभगे इति सुऽभगे ४. २६, २.
सुऽभद्राम् १८. १, १६.
सुभसत्ऽतरा २०. १२६, ६.
सुऽभागाः ९. ४, २४.
सुभिषक्ऽतमः २. ९, ५.
सुभिषक्ऽतमाः ६. २४, २.
सुऽभुवः ४. ८, ७.
सुऽभूः १३. ९, १.
सुऽभूतम् १. ३१, ३; ४; ६. ४०, २; १२. १, ५५.
सुऽभूतये १९. ४५, ६; ७; ८; ९; १०.
सुऽभूत्या ३. १४, १.
सुऽभृतम् ६. ३९, १; १३. १, १.
सुऽभेषजम् २. ३, १.
सुऽभोजसौ ४. २६, १.
सुऽमङ्गलः ८. ५, १; १६; १९. ३४, ७.
सुऽमङ्गलम् १४. १, ३०.
सुऽमङ्गली ३. १०, २; १४. १, ६०; २, २५; २६.
सुऽमङ्गलीः १४. २, २८.
सुऽमङ्गलौ ६. १४०, २.
सुऽमतयः ७. ५०, २.
सुऽमतिः १४. २, ५; २०. १४३, ७.
सुऽमतिम् २. ३६, १; ४. २३, २; २५, ६; ६. २२, २; ७. १६, १; १८, २; १०. ६, ३५; १७. १, ७; १८. १, २४; १९. ७, १; ४२, ३; २०. ७३, ३.
सुऽमतीनाम् २०. ५७, ३; ६८, ३.
सुऽमतौ ३. १०, ७; १६, ४; ५. ८, ९; ६. ४७, २; ५५, ३; ९३, ३; ७. २१, ३; ६; ९७, १; १०२, २; १३. २, ३७; १४. २, १५; ३१; १७. १, ८; ११; १८. १, ५८; २०. ९६, ५; १२५, ७.
सुमत्ऽगुः ५. १, ७.
सुऽमत्या २०. ७६, ८.
सुऽमत्यै ६. १३, २.
सुऽमनसः ३. ४, ३; १२. २, ४९; १४. २, ३६.
सुऽमनसम् ६. ९९, ३.
सुऽमनस्यमानः ७. २०, १; ४४, १; १३. १, ३५; १४. २, ३९.
सुऽमनस्यमानम् ५. २८, ९.
सुऽमनस्यमाना ११. १, ८; १२. १, ४४; १४. २, १७; ३१.
सुऽमनस्यमानाः १. ३५, १; २. ३५, ५; १३. १, १३; १९. ५८, ५.
सुऽमनाः ३. ४, ७; १२, ५; १७, ८; २०, २; ६; ६. १२३, ५; ७. ५०, २; ६२, १; ७८, ४; १९. ४९, ३; २०. २१, ४.
सुऽमन्तु १८. १, ३४.
सुमिते इति सुऽमिते २०. ७६, ६.
सुऽमृगम् १९. ८, ३.
सुऽमृडीकः ७. ९६, १; २०. १२५, ६.
सुऽमृडीका ७. ७१, १.
सुऽमृडीके ७. २१, ३.
सुऽमेधसः ७. ६३, १; २.
सुऽमेधाः १९. ४०, २.
सुऽमेधाः ५. ११, ११; ७. ६२, १; ९. १, ६.
सुऽमेधाम् ४. ३०, ३.
सुम्नम् २०. २६, ६; ३६, ४; ४६, ३; १०८, २.
सुम्नऽया ७. ५७, २.
सुम्नयि १९. ४७, ४.
सुम्नऽयुः ७. ११, १.
सुम्नऽयौ ३. १७, १.

सु॒म्नेभि॑ः २०. १४२, ६.
सुऽय॑तः ६. १११, १; २०. ११७, १.
सु॒ऽयम॑म् ७. ७७, १०; ८७, ३.
सु॒ऽयम॑स्य १९. १०, २.
सु॒ऽयमा॑ १४. २, १७; १८; २०. ९४, २.
सु॒ऽयमा॑न् ४. २७, १.
सु॒य॒व॒स॒ऽअत् ७. ७७, ११; ९. १५, २०.
सु॒ऽयव॑से ४. २१, ७; ७. ७९, १.
सुऽया॑मन् १६. ७, ७.
सु॒याशु॑ऽतरा २०. १२६, ६.
सुऽयु॑क्तान् २०. ९२, १०.
सु॒ऽयुज॑ः ५. २६, ३; ७; ८; ९; १०; ११.
सु॒ऽरत्ना॑ः १२. २, ३१; १८. ३, ५७.
सु॒र॒भय॑ः १८. ३, १७.
सु॒र॒भि ६. १२४, ३; २०. १३७, ३.
सु॒र॒भिः १२. १, ५९; १४. २, ४४; १९. ३८, १.
सु॒र॒भिम् १२. १, २३; २४.
सु॒र॒भीः ११. ६, ६.
सु॒र॒भीणि॑ १८. ३, ४२.
सुरा॑ ६. ७०, १; १४. १, ३६; १५. ९, २.
सुरा॑ऽउदकाः ४. ३४, ६.
सु॒ऽराध॑सम् २०. २९, २; ५१, १; ३.
सुरा॑म् १०. ६, ५.
सु॒राम॑म् २०. १२५, ४.
सु॒ऽराम॑म् २०. १२५, ५.
सुरा॑याः १५. ९, ३.
सुरा॑याम् ६. ६९, १; ९. १, १८; १४. १, ३५.
सु॒रा॒श्व᳚ः २०. ११४, २.
सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे ५. १२, ६.
सु॒ऽरुच॑ः ४. १, १; ५. ६, १; १८. ३, २२.
सु॒ऽरुच॑म् ४. १, २.
सु॒रू॒प॒ऽकृ॒त्नुम् २०. ५७, १; ६८, १.
सु॒ला॒भि॒के॒ २०. १२६, ७.
सु॒व॒ २. २९, २; ५. २२, ३; ७. १५, ३; १९. ८, ४; ३९, १०.
सु॒व॒ता॒म् ४. २५, ५.
सुव॑ते ९. १४, २१.
सु॒ऽवर्चा॑ः २. २९, ६; ७; १३. १, २२; १४. १, ४७; २, १८; १८. २, १०; ३, ५८.
सु॒ऽवर्ण॑म् १५. १, २; १९. २६, २.
सु॒ऽवर्णा॑ १३. १, २२.
सु॒ऽवर्णा॑ः १. ३३, १; २; ३; १२. ३, २८; २०. १६, ३.
सु॒ऽवर्णै॑ः १३. ३, १६.
सु॒ऽवर्हि॑म् १३. २, ७.
सु॒ऽवह्ना॑ २०. ३६, ७.
सु॒ऽवाच॑ः २. ५, २.
सु॒ऽवाचा॑ ५. १२, ७.
सु॒वा॒ति॒ १४. १, ३३.
सुवा॑ना २. ३६, ३.
सु॒वा॒नास॑ः २०. ११८, ४; ११९, २.
सु॒वा॒म॒ १९. ५७, २.
सु॒वा॒म॒सि॒ १. १८, १; ६. १२७, ३; ७. ५५, ६; १२. २, ३.
सु॒वा॒मि॒ १. १०, २; ४. १३, ५; ६. ११९, ३; ७. ५५, ६.
सु॒ऽवासा॑ः १४. २, ४४.
सु॒ऽवि॒ज्ञा॒नम् ८. ४, १२.
सु॒वि॒ता २०. १२६, २१.
सु॒वि॒ताय॑ १९. १०, १.
सु॒ऽवि॒दत्र॑ः १३. २, ४४; ४५.
सु॒ऽवि॒दत्र॑म् १. ३१, ४.
सु॒ऽवि॒द॒त्राः १८. ३, १९.
सु॒ऽवि॒दत्रा॑न् १८. १, ४५; २, ११.

सुऽविदत्रियेभ्यः १८. २, ९४.
सुऽविदत्रेभिः १८. ३, ४८.
सुऽविद्वांसः ४. १४, ४.
सुऽविद्वांसम् २०. ६६, २.
सुऽवीरः ६. ११०, ३; १२९, १; ८. ९, २; ११. १, २; १२. २, ४९; १३. १, १२; १९. २४, ८.
सुऽवीरतायै ६. २९, ३; ७. २१, ९.
सुऽवीरम् ३. १९, ९.
सुऽवीरम् ७. २१, ४; ८४, १.
सुऽवीराः ३. १०, ९; १२, १; ५. ३, ९; १८. २, ५९; ३, २४; ४, ६३; १९. १२, १; २०. २१, ११; ६३, ३; १२४, ६.
सुऽवीरासः १२. २, २२; २०. ३४, १८.
सुऽवीर्यः ७. १०२, ६.
सुऽवीर्यम् २०. ९, ३; ४९, ६; ९३, ४; १०८, ३.
सुऽवीर्यस्य ७. ९६, १; २०. १२९, ६.
सुऽवृक्ति २०. ३९, २; ४; १६.
सुवृक्तिऽभिः २०. ३९, ३.
सुऽवृजनासु १८. १, ४६.
सुऽवृतम् १४. १, ६१.
सुऽवृता २०. १४३, ९.
सुऽवृधा २. १३, ९.
सुवे ४. ३०, ७.
सुऽव्रतानाम् ७. ६, २.
सुऽशंसः १९. १०, ६.
सुऽशंसिनः ६. ६, २.
सुऽशकुनम् १९. ८, ३.
सुऽशर्म १९. ७, ९.
सुऽशर्माणम् ७. ६, २; ७, १.
सुऽशिप्र २०. ७१, ९; ८०, १; ९२, १३.
सुऽशिप्रः २०. ३०, ३; ३४, ६.
सुऽशीमम् ३. १७, ३.
सुऽशृतम् ७. ७६, १.
सुऽशेवम् ४. २५, ५; ६. १, २.
सुऽशेवा १३. १, १७; १४. २, १७; २६; १८. २, ३१.
सुऽशेवाः २. २, २; १४. १, १९; ५८.
सुऽशेवाम् १८. ३, ४९.
सुऽशेवौ ५. ६, ५; ६; ७.
सुऽश्रवः ११. ६, १९.
सुऽश्रवसम् २०. २१, १०.
सुऽश्रवसा २०. २१, ९.
सुऽश्रुत् ८. २, ८.
सुऽश्रुतिः १६. २, ५.
सुऽश्रुतौ १६. २, ४.
सुषिराम्ऽइव २०. ९२, ९.
सुऽसंनता ३. २५, ३.
सुऽसंनताम् ३. २५, २.
सुऽसंशासः १८. ३, १६.
सुऽसंशितः ६. १०५, २.
सुऽसदा ३. १४, १.
सुऽसदाः २. ३६, ४.
सुऽसदाम् ३. २२, ६.
सुऽसंमृद्धेन ९. ९, २; ४; ६; ८.
सुऽसह ६. ६४, ३.
सुऽसहान् २०. ८०, २.
सुऽसायम् १९. ८, ३.
सुसाव २०. ११७, १.
सुसुम २०. ३, १; ३८, १; ४७, ७.
सुसुम २०. ७७, १.
सुसुवे १४. १, ४३.
सुसूदत १. २६, ४.
सुऽसूमा ७. ४८, २.
सुऽस्तुतः २०. ११५, ३.
सुऽस्तुतिम् ७. ८७, १; २०. ७०, १३.

सुऽस्तुती ७. ९०, १.
सुस्तुती इति सुऽस्तुती ६. १, ३.
सुऽस्तुतीः ६. ३९, १; २०. ४, १.
सुऽस्तुत्या ७. ३०, २; २०. ४४, ३.
सुऽस्तुभः २०. २, १; २; ३; ४.
सुऽस्तुभा २०. ८८, ५.
सुऽस्थामा २०. ९४, २.
सुऽस्नुषे २०. १२६, १३.
सुऽस्यदाः १९. ४०, २.
सुऽस्रसः ७. ८०, १[२].
सुस्रुवुः ७. ११७, १; १४. २, ४५.
सुस्रोः १२. ३, २२.
सुस्रोत् २. २९, ७; १९. ५८, ४.
सुस्वयन्ती इति ५. १२, ६; २७, ८.
सुस्विऽतराय २०. ३७, १.
सुस्विम् २०. ३५, १५.
सुऽहन्तु २०. ३७, ४.
सुऽहवः ७. ११, १; १९. ४, ३.
सुऽहवम् ७. २१, ४; ९१, १; १७. १, ११; १९. ७, २; ८, ३.
सुऽहवा ३. २०, ६; ७. ४९, १; ५०, १; ११. १, २६; १९. ४, २; ७, ३; ४९, १; ५.
सुऽहवाः ७. ५१, १.
सुऽहवानि १९. १०, ३.
सुऽहस्तः ७. ७७, ७; ९. १५, ४.
सुऽहस्ताः १९. ११, १.
सुऽहार्त् २. ७, ५.
सुऽहार्दः ३. २८, ५; ६. १२०, ३; १९. ३२, ६.
सुऽहार्दम् ३. २८, ६.
सुऽहिता ११. १२, ४.
सुऽहुतम् ६. ७१, १; २; १०. ९, २६.
सुऽहुते ७. ४, १.
सूकरः २. २७, २; ५. १४, १.
सूकराय १२. १, ४८.
सूचीऽमुखाः ११. १२, ३.
सूच्या ७. ५०, १.
सूतऽवशा १२. ४, ४४; ४६; ४७.
सूतवे १. ११, २; ५. २५, १०; ११; १२; १३.
सूतवै १. ११, १.
सूताः ३. ५, ७.
सूतिकाः ८. ६, १९.
सूतुम् ६. १७, १; २; ३; ४.
सूते ९. १४, १७; १३. १, ४१.
सूतौ १. ११, १.
सूत्रम् १०. ८, ३७[२]; ३८[२].
सूत्रस्य १०. ८, ३७; ३८.
सूत्री ९. १२, १४.
सूत्रे ३. ९, ३.
सूदयतु १. १८, ३.
सूदयन्तु ६. ५१, २.
सूनवः २०. ६७, ४.
सूनानाम् ५. १७, १४.
सूनाम् २०. १२६, १८.
सूनुः ७. ३६, ३.
सूनुः ६. १, २; ७. १, २.
सूनुम् १२. ३, २३; २०. २२, ४; ६७, ३; ९२, १.
सूनृता ३. २०, ३; ११. ९, १३; १२. ५, ६; १९. ७, २; २०. २७, ३; ४५, २; ६०, ४; ७१, ४.
सूनृताम् ६. ६२, २; १०. ६, १३.
सूनृताऽवत् ५. २०, ६; १३. १, १; २०.
सूनृताऽवती ३. १२, २.

सूनृताऽवते ३. २१, ५.
सूनृताऽवन्तः ७. ६२, ६.
सूनृते ८. ११, ४.
सूनृते २०. १४२, २.
सूनो इति १८. १, २४; २०. १०३, ३.
सूरः ४. २, ४; ६. ६१, १; ७. ७५, २; १३. २, २४; १८. ४, ५८; ५९; २०. ४७, २१; ७६, ५.
सूरयः ४. ३३, ३; ४; ७. २७, ७.
सूराय १३. २, १७; २०. ४७, १४.
सूरिः २. ११, ४; १३. १, २२; १८. ३, ३९.
सूरिऽभिः ७. १०२, २; २०. ७३, ४.
सूरिम् ३. १९, ३; ९. ५, २; २०. ३५, ३.
सूरिषु २०. ३७, ७.
सूर्म्यम् २०. ९२, ९.
सूर्ये २. १६, ३; २१, १; २; ३; ४; ५; १३. २, ७; १२; १७. १, २६; १९. ७०, १.
सूर्य १३. १, ३२; ५८; २, ५; ६; १९; २२; २३; २९; ३७; १७. १, ६; ७; १९. ६५, १; २०. ७, १; ४७, १६; १९; २०; ५८, ३; ४; ११२, १.
सूर्यः १. ४, २; ९, २; २९, ५; २. १०, ४; १५, ३; २९, १; ४. ४, २; ५. ९, ७; १३, ३; १७, ९; २३, ६; २४, ९; २८, २; ३०, ११; १५; ६. ८, ३; १२, १; ५२, १; ७५, ३; ८३, १; ९१, २; १००, १; ७. १४, १; ७२, १; ८७, ४; ८. १, ५; १२; २, १४; ५, १८; ६, ८; ९. २, २४; १०, ४; १०. १, ३२; ३, १७; ६, ९; ७, १२; ३३; ८, १६; १०, ३४; ११. ६, १२; ९, १४; १०, ३१; १२. १, १५; ५३; ११, १२; १३. १, ४५[४]; २, ८; १४; ३४; ३५; ४, ५; १५. ६, ५; १६. ४, ४; १७. १, ३०; १८. १, २७; १९. ६, ७; १०, ८; १७, ५; १९, ३; २०, ४; २७, २; ४३, ३[२]; ४४, ५; ५३, ६; ५४, १; २०. २५, ५; ९२, १७; १०५, ५; १०७, १३; १४; १५; १२३, २.
सूर्यःऽइव ७. १४, २; ८. ५, ७; १९. ३३, ५; २०. ११५, १.
सूर्यऽकेतवः ५. २१, १२.
सूर्यऽतेजाः १०. ५, २७.
सूर्यऽत्वक् २. २, २.
सूर्यऽत्वचम् १४. १, ४१.
सूर्यऽत्वचसः १. २६, ३.
सूर्यपत्नी इति सूर्यऽपत्नी ८. ९, १२.
सूर्यम् १. ३, ५; ६, ३; २२, १; ३१, ४; २. १०, ८; ३. २०, ४; ३१, ७; ४. ४०, ७; ६. ६०, ३; ६२, ३; ७. ३९, ३; ५५, ७; ११४, ३; ८. ४, २४; ५, ६; ६, १२; ९. १५, ३; १०. १०, २५; ११. ८, १; १२. २, १८; १३. १, २५; ३५; ३९; ५६; २, २; १६; ३२; ४३; १४. २, ३४; १८. २, ७; १८; ५०; १९. १८, ५; २७, ७; २०. ८, १; ११, ९; १७, ५; ३४, ७; ३८, ६; ४७, ६; १३; ५८, १; ६२, ६; ७०, ९; ९१, ५; ११८, ४.
सूर्यम्ऽइव ४. २०, ७.
सूर्यऽवतः ९. ५, १८.
सूर्यऽवर्णे ५. ५, ६.
सूर्यऽश्रितः ६. ४९, ३.
सूर्यस्य ३. १६, ४; २२, ४; ४. ३८, ५; ६. १०५, ३; १०८, १; ५; ७. ५, ३; १२,

१; ८७, ९; ११२, १; ८. १, १; ४; ९. १४, १४; १०. ५, ३७; १३. १, २४; १५. ६, ६; १६. ९, ३; १८. १, १०; २८; १९. २७, ५; २०. ८७, ६; १२३, १.
सूर्या १४. १, ६; १०; १२; २, ३०.
सूर्याऽइव १४. २, ३२.
सूर्याः १३. ३, १०; २०. ८१, १; ९२, २०.
सूर्याःऽइव २०. १०, २; ५९, २.
सूर्याचन्द्रमसाभ्याम् ६. १२८, ३.
सूर्याचन्द्रमसाभ्याम् ११. ४, ३.
सूर्याचन्द्रमसौ ८. २, १५; ११. ३, २; ८, ५.
सूर्यात् ५. १०, ८; ८. २, ३; ६, २४; १०. ७, ३१.
सूर्यान् १९. २७, ४.
सूर्याभ्याम् १९. २३, २४.
सूर्याम् ६. ८२, २; १४. १, ९; १५; २९; २, १; २०. १४३, १.
सूर्यामासयोः ३. २९, ५.
सूर्यामासा २०. १६, १०.
सूर्याम्ऽइव १४. १, ५३.
सूर्याय ६. १०, ३; १८. २, १३; ४६; १९. ४३, ३; २०. ३२, १.
सूर्यायाः ९. ४, १४; १२. १, २४; १४. १, ७; ८; १३; १४; २८; ५५.
सूर्यायै १४. २, ४६.
सूर्ये १. ४, २; ६. ३८, १; १०. ४, २२; ११. ७, १३; १४. १, १६; १८. १, ३५; २०. ३५, १५.
सूर्ये १४. १, ६१.
सूर्येण ४. १८, १; ३६, ५; १०. १०, १५; १२. १, ३३; १४. १, १; १९. २६, २; २०. १४२, ३.
सूषणे १. ११, ३.
सूषा १. ११, ३.
सृकम् ७. ८९, ३.
सृकाणम् ९. १५, ६.
सृज ५. १६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ८. २, ७.
सृज १. ११, ३; ३. १०, ३; ८; ४. १५, १२; ५. २, ३; २७, ११; २८, ४; ३०, १४; ६. ५, १; २; २६, १; ७. ९४, १; २; ९. १, १४; १५; १०. ५, ४६; ४७; ११. ११, १२; १२. १, २५; १५. १२, २; १८. २, १०; २०. १०७, ६.
सृजत् ८. ४, २०.
सृजत १२. ३, ४६; २०. ७१, ८.
सृजतम् ४. २८, ७.
सृजताम् १२. १, १०.
सृजति ७. ५२, ६; १०. १०, २४; १९. २६, २; २७, ७; २०. ८९, ९.
सृजतु २. ३५, २; ३. १४, २; १४. १, ३४ १९. ३१, २.
सृजते ६. ३६, २.
सृजथः ४. २५, ४.
सृजन्ति ४. २७, ४.
सृजन्तु ४. १६, ६; ७. ११४, ३.
सृजन्ते १३. १, २५.
सृजाति ६. ११६, २; १९. ३३, १.
सृजामसि ३. १४, १; ५; ७. १२०, १; १४. २, ५३; ५४; ५५; ५६; ५७; ५८.
सृजामि १०. ५, १५; १६; १७; १८; १९; २०; २१; १२. २, ३२; ५५; १६. १, ४; ७; २०. २२, १.
सृजेथाम् १२. ३, ३९; १४. २, ३७.
सृज्यन्ते १२. २, ३९.
सृण्यः ३. १७, २.

सृतिम् १०. ३, ६.
सृधः २. ६, ५.
सृन्ऽर्जयाः ५. १९, १.
सृपः ८. ६, ३[२].
सृपत् ६. १३४, २; १२. १, ४६.
सृप्रम् २०. ८८, २.
सृष्टम् ४. १५, ६.
सृष्टा १२. ५, १.
सृष्टाः ८. ३, १४.
सृष्टा३ः १०. २, २८[२].
सृष्टीः १३. १, २५.
सृष्ट्वा ३. २८, १.
सेकम् २०. ७७, ३.
सेक्ताऽइव २०. ८, ३.
सेचते २०. ३०, १.
सेचिरे ८. ९, २३.
सेतवे ५. ६, ३.
सेतौ २०. ९१, ४.
सेदिः ८. ८, ९.
सेदिः २. १४, ३; १२. ७, १३.
सेदिम् ४. ११, १०; ८. ८, १८.
सेदुः १२. १, ३०.
सेदुः ८. ९, १७; १७. १, १४; २०. ८८, ३.
सेध ३. १५, ५; ६. १२६, १; २.
सेधतम् ४. २५, ४.
सेधति ८. ३, २६.
सेधन्ति ५. १९, ९.
सेधसि ६. ८१, १.
सेधामि ८. २, ११.
सेनया ३. १९, ६; ६. ९३, १; ८. ८, ७; ११. ११, ४; ५; ६; १९; १२, ५; ६; ७; १८; २१.
सेना ३. २, ६; ११. १२, ४; २५; १५. ९, २.
सेनाऽइव ४. १९, २.
सेनाः ५. २१, ९; ६. ६७, १; ८. ८, १; ११. ११, ३; १२, २०; १९. १३, २; ७; १५, २.
सेनाऽनीः ४. ३१, २.
सेनाभिः ६. ६६, १.
सेनाभ्यः ११. २, ३१.
सेनाम् ३. १, १; ५; ६; ८. ८, २; ५; १३; १४; १५; १७; १८; ११. ११, ५; १२, १३.
सेनायाः ८. ८, १६; १५. ९, ३.
सेनायाम् ५. ३१, ७.
सेन्यः १. २०, २; ६. ९९, २; २०. ५६, २.
सेन्यम् १८. १, ४०.
सेवते ११. १०, ३३.
सेवस्व ५. ३०, ५.
सेहोः ७. ८०, १.
सैन्धवम् १९. ३८, २.
सो इति १८. १, २०; २०. ७३, ५.
सोतुः २०. ११७, १.
सोतोः २०. १२६, १.
सोत्वासः २०. ९६, २.
सोभरी १८. ३, १५.
सोम ६. ९९, ३; ११. १, २६.
सोम १. २०, १; ५. ३, ७; ६. ६, २; ३; ७, १; २; ८. ४, २५; ९. १४, १९; १४. १, ४; ५.
सोमः १. ६, २; २९, ३; २. १०, २; ३६, ३; ३. ३, ३; १५, ६; २७, ४; ५. १७, २; १८, ६; १४; २१, ११; २२, १; २४, ७; २६, १०; २९, १०; ६. ३, २; ५,

३; १५, ३; २१, २; ३९, ३; ४०, १; ५१, १; ५३, १; ५८, ३; ७३, १; ८७, ३; ९६, ३; ९७, १; १०४, ३; ७. १९, २; ११९, २; १२३, १; ८. १, २; ४, ९; १२; १३; ५, ५; ७, २०; १३, १४; ९. १, ११; १२; १३; २, १३; १२, २; २२; १५, १४; १०. १, २२; ४, २६; ६, ८; १०, ७; ११. ७, १४; ८, ७; १०, ८; ९; १२. ३, ९; २४; ३१; १४. १, १; २; ९; ४९; ५४; २, ४; १५. २, २२; १४, ७; १६. ९, २; १८. २, १; १४; ३, २८; ५५; ४, ६०; १९. १०, ७; १३, ९; १७, ३; १९, ५; २०, १; २४, ८; २७, २; ४३, ५[२]; ४५, ८; ५८, २; २०. ४, ३; ५, १; ५; ३४, १५; ८७, ५; १३७, ६; १३९, ४.

सोम॑ऽकामम् २०. ८, २; ११३, २.

सो॒म॒ऽजाः ४. ३, ७.

सोम॑ऽजुष्टम् २. ३६, २.

सोम॑ऽतेजाः १०. ५, ३२.

सो॒म॒ऽधान॑ः ७. ११६, १; ९. १, ६.

सो॒म॒ऽप॒ १. ८, ३; २. १२, ३.

सो॒म॒पर्व॑ऽभिः २०. ७१, ७.

सो॒म॑ऽपाः १८. ३, ६४.

सो॒म॒ऽपाः १. २१, १; ५. २५, ९; ८. ५, २२; १९. १३, ४; २०. २९, ५; ३४, १४.

सो॒म॒ऽपा॒ः २०. ५७, २; ६४, २; ६८, २; ७४, १.

सो॒म॒ऽपात॑मः २०. ६३, ७; ७१, ३.

सो॒म॒ऽपान् २. ३५, ३.

सो॒म॒ऽपाम् २०. ३, ३; २३, ५; ३८, ३; ४७, ९.

सोम॑ऽपायिनः १८. ३, ६४.

सो॒म॒ऽपावा॑ २०. १२, ७.

सो॒म॒ऽपान्नै॑ ६. २, ३.

सोम॑ऽपीतये १७. १, १०; २०. २३, १; २४, ३; ६०, ६; ७१, ६; ११३, १; १२६, २; १३७, २.

सो॒म॒ऽपी॒थम् १८. ३, ४६.

सो॒म॒ऽपी॒थे १०. ३, २१.

सोम॑ऽपुत्रे ३. १०, १३.

सोम॑ऽपृष्ठः १३. १, १२.

सोम॑ऽपृष्ठा ७. २८, १.

सोम॑ऽपृष्ठाः ३. २१, १०.

सोम॑ऽपृष्ठाय ३. २१, ६; २०. १, ३.

सो॒म॒ऽपेया॑य २०. २९, २.

सोम॑म् २. ५, ७; ३. ८, ३; १६, १; २०, ४; ४. ६, १; ३०, ६; ४०, ४; ६. २, १; ३; ७. १५, ४; ३९, ३; ६०, १; ८१, २; ९९, १; १०२, १; १०. २, १९; ७, ३६; १०, ३; ९; १२; ३२; १२. १, ३८; १३. १, २; २७; १४. १, ३[२]; १९. १८, ३; २४, ३; २०. २, १; २; ३; ४; ३, १; ६, २; ५; ७, ४; १३, १; २०, १; २४, १; ८; ३२, ३; ३८, १; ४२, ३; ४७, ७; ५७, ४; ६७, ४; ७; ८६, १; ८७, ३; ९२, ७; ९५, १; ९६, २; ३; ४; १०९, २; १११, १; ११७, १; १४०, २.

सो॒म॒ऽयो॒गैः १०. ५, ४.

सोम॑ऽराज्ञीः ६. ९६, १; ८. १, १७.

सोम॑वत्ऽभ्यः १८. ४, ७३.

सोम॑ऽवर्चसः १४. १, ३२.

सोम॑ऽशितम् ८. ४, १९.

सोम॑ऽश्रेष्ठानि ११. ८, १५.

सोमसत्ऽसरु ३. १७, २.
सोमस्य २. ५, ३; ३. ५, ४; ४. ४, ५; २१, ५; ५. ४, ७; २८, ६; ६. ६८, १; ३; ७. ६०, २; ८६, ३; ९. ४, ५; १५; १०. ५, ९; ११. १, १८; १४. १, ४; २, ३; १५. २, २४; १९. ६, १६; ५९, २; २०. ६, ७; २४, ४; २८, १; ३९, २; ५४, २; ५७, २; ६८, २.
सोमस्यऽइव ५. २९, १३.
सोमाः २०. ६, ४; २४, ५; ३१, १; ८९, ८; १३७, ४.
सोमात् ४. १०, ६; ११. १०, ९.
सोमान् २०. ८७, २; ८९, ५.
सोमाय २. १३, २; १२. ३, ५८; १५. २, २३; १८. ४. ७२; १९. २४, ४; ४३, ५.
सोमारुद्रा ७. ४३, १; २.
सोमारुद्रौ ५. ६, ५; ६; ७.
सोमासः २०. ८, ३; १७, ४; ७; २१, ६; ६९, ३; ५; ११२, ३; १४१, ४.
सोमिनः ४. २४, ५; १३. १, ५९; २०. ३, ३; ३८, ३; ४७, ९; ९४, ५.
सोमिनि २०. ५९, ३.
सोमे ३. २१, २; २०. १, १; ६, १; १७, २; ६८, १२; ८९, १.
सोमेन ५. ७, ५; १७, ५; ६. ८९, १; ९. ४, ६; १०. १०, १३; ११. १, २५; १४. १, २^{२}; १८. ३, ८; १९. ३९, ५; ६; ७; ८.
सोमैः २०. १७, ६.
सोम्यः २०. ४७, २; १३७, १३.
सोम्यम् ३. १४, ३; ९. ३, १९; १८. ३, १९; २०. ६७, ५; ७.
सोम्यस्य २०. १४३, ४.
सोम्याः ९. ५, १५.
सोम्यानाम् १८. ३, ५३.
सोम्यासः २. १२, ५.
सोम्यासः १८. १, ४४; ५८; ३, १०; ४५; ४, ६२; ६३.
सोम्येभिः ४. ३४, ३.
सौत्रामण्या ३. ३, २.
सौधन्वनाः ६. ४७, ३.
सौपर्णम् १६. २, ५.
सौप्रजाःऽत्वम् २. २९, ३.
सौभगऽत्वाय १४. १, ५०.
सौभगम् २. ३६, १; ६. ११०, १.
सौभगाय १. १८, २; २. ६, २; ३. १२, २; ४. ८, ७; ५. २८, १४; ७. १७, १; ३६, १; ७७, ८; १०; ९. १५, ५; १४. २, ३०; १७. १, ९.
सौभाग्यम् १४. १, ४२; २, २८.
सौमनसः ३. ३०, ७; ७. ६२, ३.
सौमनसम् १३. १, १९; १४. १, ४२.
सौमनसस्य १९. ५५, ३; ४.
सौमनसे ६. ५५, ३; ७. ९७, १; १८. १, ५८; २०. १२५, ७.
सौम्येन १९. ४५, ८.
सौर्यऽवर्चसः ८. १४, ६; ७.
सौवश्व्ये २०. ३५, १५.
सौश्रवसम् २०. ८७, ४.
स्कन्द ५. २५, ८.
स्कन्धः १०. ७, ३८.
स्कन्धाः ९. १२, ३; १०. ९, २०.
स्कन्धान् ६. १३५, १; १०. २, ४; १२. ११, ६.
स्कन्ध्याः ६. २५, ३.
स्कभायति २०. ९४, ८.

स्कभिता ७. २६, १.
स्कम्भे १०. ७, २९.
स्कम्भः ५. १, ६; १०. ७, ८; ९[2]; २६; २८; ३५[3].
स्कम्भम् १०. ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २२; ३९; २०. ९४, ४.
स्कम्भस्य १०. ७, २; २५; २६.
स्कम्भे १०. ७, २९[3]; ३०; ३५; ८, २.
स्कम्भेन १०. ८, २.
स्त ६. ७३, ३; ७. ६२, ४; ६; ७.
स्त इति स्तः २०. ३५, ८.
स्तन ६. १२६, २.
स्तनः ७. ११, १.
स्तनथौः ५. २१, ६; ८. ७, १५.
स्तनय ४. १५, ६; ५. २०, ७.
स्तनयति ८. ७, २१; ९. १, २४.
स्तनयति १३. ७, १३.
स्तनयन् १. १२, १; ९. १०, ६; ११. ७, १२.
स्तनयन्ऽइव २०. ९१, ५.
स्तनयित्नवे १. १३, १; ११. ६, २.
स्तनयित्नुः ७. १२, १; ९. १, १०; २०; १२, १४; ११. ९, २०; १५. २, २५.
स्तनयित्नुना ४. १५, ११; ११. ६, ३.
स्तनयित्नून् ९. २, १९.
स्तनस्युम् १२. ३, ३७.
स्तनाः ९. १२, १४; १०. ९, २२; १०, ७.
स्तनान् १२. ४, १८.
स्तनेभ्यः १०. १०, २०.
स्तनौ ८. ११, ६; ९. १, ७; १०. २, ४.
स्तब्ध्वा १०. ७, ७.
स्तभान ९. ५, १५.
स्तभितम् १३. १, ७.
स्तभ्नामि १८. ३, ५२.
स्तम् ३. ११, ६; ५. ९, ८[2]; १४. १, २२.
स्तम्बऽजः ८. ६, ९.
स्तम्बिनीः ८. ७, ४.
स्तम्बे ८. ६, १४.
स्तम्भेन १९. ३२, ७.
स्तरीतवे २. २७, ३; ४.
स्तर्यः २०. १२, ४.
स्तवते २०. ६४, ४.
स्तवते ७. २७, २.
स्तवमानः २०. ३७, ११.
स्तवान २०. ६, ३.
स्तवानः १८. १, ४०.
स्तवानः २०. ९८, २.
स्तवाम १३. २, २; २०. ६५, १.
स्ताम् ६. ७८, २.
स्ताम् २. १०, १; २; ३; ४; ५; ६; ७; ८; ३. ४, ५; ७. ५५, २; ८. २, १४; १८; ९. ४, १०; १०. ९, २५.
स्तामानम् ५. १३, ५.
स्तीन् २०. ३७, ११.
स्तीमासु ११. १०, ३४.
स्तीर्णम् १२. ३, ३३.
स्तुकाम्ऽइव ७. ७८, २.
स्तुतः १९. ३, १; २०. १२, ६; २७, ४.
स्तुतम् ११. ९, ५.
स्तुता १९. ७१, १.
स्तुत्वा ९. २, २.
स्तुप्तः १९. ४, १.
स्तुमः ३. १५, ७.
स्तुवतः २०. ५०, २.
स्तुवताम् १. ८, १.

स्तुवते ५. ११, ११; २०. १७, १२; ५१, ३; ८७, ७.
स्तुवन् ४. २८, ३.
स्तुवन्तः २०. ५०, २.
स्तुवन्ति २०. ६१, ३; ९९, २.
स्तुवानः १. ८, २.
स्तुवानम् १. ७, १.
स्तुवानस्य १. ८, ३.
स्तुषे १८. १, ३७.
स्तुषे २०. १४, ३; ६२, ३.
स्तुष्व ५. २, ७; २०. १०७, १०.
स्तुहि ६. १, १; १८. १, ४०; २०. ६६, १.
स्तुहि ६. १, २; २०. ५८, २; ६६, २.
स्तृणवामहै १०. ५, ४२.
स्तृणामि १८. ४, ५१.
स्तृणीत १२. ३, ३२.
स्तृणीहि ७. १०४, १; १२. ३, ३७; १४. २, २३.
स्तृषीय १०. ५, १५; १६; १७; १८; १९; २०; २१.
स्तेगः १८. १, ३९.
स्तेनः ४. ३, ५; २१, ७; ७. ७९, १; ८. ४, १०; १९. ४७, ६; ७; ४९, ७; ९.
स्तेनम् ४. ३, ४; १९. ५०, ५.
स्तेनैः ४. ३६, ७.
स्तेयऽकृत् ८. ४, १०.
स्तेयम् ११. १०, २०; १४. १, ५७.
स्तोकः ६. १२४, १.
स्तोकाः ४. ३८, ६; १२. ३, २८.
स्तोकान् २. ३५, २.
स्तोत २०. ४४, १; ८५, १.
स्तोता २०. २७, १.
स्तोतारः ७. १०, ३; १९. ४८, ४; २०. ५२, १; ५७, १४.
स्तोतारम् २०. २३, ६; ५५, २; ८२, १.
स्तोतुः ६. २, १; २०. १५, ५; ५३, ३; ५७, १३; ११९, १.
स्तोतृऽभ्यः १८. ४, ८८; २०. १४, ४; ६२, ४; १२२, २.
स्तोतृणाम् २०. २९, १.
स्तोत्रम् ५. ११, ८; २०. ४५, २.
स्तोत्राणि ५. ११, ९.
स्तोभन्तु २०. ११०, १.
स्तोमः २०. २८, ४; ३९, ५; ६०, ६; ७१, ६; ७६, १.
स्तोमऽतष्टासः १८. ३, ४७.
स्तोमम् ६. ३५, ३; ७. ५२, ३; १७. १, ११; १९. २७, ३; २०. १३, ३; १८, २; ३५, १; ४; ८९, १; ९७, २; ११६, २; १४०, २; १४३, ६.
स्तोमऽवर्धनः २०. २९, १.
स्तोमऽवाहसः २०. ६८, ११; १२०, २.
स्तोमस्य १९. ४९, ५; ६.
स्तोमाः ४. २४, १; ८. ९, ६; १९; १४. १, ८; २०. ३७, १०; ६९, ६; ७०, १३; ९३, १; १४०, ३.
स्तोमासः २०. १०, १; ५९, १.
स्तोमेन २०. १३९, ४.
स्तोमेभिः २०. १९, २; ५९, २; ७१, ९; ७२, १; ९९, १.
स्तोमेषु ८. ९, १९; २०. २३, ४.
स्तोमैः २०. १, ३; २४, ४; १०४, १; १३८, १; ३.
स्तोम्यम् २०. ३१, १; ६५, १.
स्तोषाम २०. २१, ११.

स्तौति ९. १०, १; ४; ६; ८.
स्तौतु ९. ४, ११; १३. १, २७.
स्तौमि ४. २३, ७; २४, ७; २५, ७; २६, ७; २७, ७; २८, ७; २९, ७.
स्त्रियः ४. ५, २; ३; ३७, ११; ६. १३८, ५; ९. १४, १५.
स्त्रियम् ८. ४, २४; ६, ९; १६; २५.
स्त्रियाः ५. १७, ८; १२. २, ३९.
स्त्रियाम् ६. ११, २; ७०, १; २; ३.
स्त्रियै ५. ३०, ३.
स्त्री १. ८, १; ५. १४, ६; ७. १००, ३; १०. ४, ८; ८, २७; २०. १२६, ६.
स्त्रीऽकृता १०. १, ३.
स्त्रीणाम् ७. १४, १; ८. ६, १३.
स्त्रीऽभागान् ८. ६, १९.
स्त्रीषु ६. ११, १; ७. ९५, ३; १२. १, २५.
स्त्रैणम् ४. ३४, २; ८. ६, ४.
स्त्रैसूयम् ६. ११, ३.
स्थ १. ५, १; ३०, ३; २. १२, २; १४, ५^{२}; २४, १; २; ३; ४; ५; ६; ७; ८; ३. २६, १; २; ३; ४; ५; ६; ६. २१, ३; ५०, ३; १०. १, ३०; १२. २, २४; १८. ३, २०; २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४; ८६; १९. २७, ११; १२; १३.
स्थ ३. १, २; १३, १; ७. ७९, २; १०. ५, १^{५}; २^{५}; ३^{५}; ४^{५}; ५^{५}; ६^{६}; ७; ८; ९; १०; ११; १२; १३; १४; १६. २, २; ४, ७; १९. ६९, १; २; ३; ४.
स्थने १. ३१, २; ३. ८, ५; ६. २४, ३; ९४, १.
स्थन ३. १३, २; ६. ६६, २.
स्थपतिः २. ३२, ४; ५. २३, ११.
स्थविरः ९. ४, ३; १९. १३, ५.
स्थविरस्य १९. १५, ४.
स्थविरौ १९. १३, १.
स्थाः ५. ७, १.
स्थाणुम् १०. ४, १; १४. २, ६.
स्थाणौ १४. २, ४८; ४९; १९. ४९, १०.
स्थात ५. १३, ५.
स्थातः २०. ६४, ५.
स्थात्रे ९. १४, १६.
स्थापय १२. ३, ३०.
स्थापयत ५. २, ६; २०. १०७, ९.
स्थापयाति ७. ४०, १.
स्थापयामसि ४. ७, ४; ५; १०. १, २९.
स्थाम १. ३२, २; १२. ४, २९; ३०.
स्थाम्नि ४. ७, ५; ६. ७७, १; ७. १०१, १.
स्थालीम् ८. ६, १७.
स्थिरः २०. २०, ५; ५३, ३; ५७, ८; १३; ६०, १.
स्थिरऽधाम्नः १०. ४, ११.
स्थिरम् ५. २, ४; २०. ८६, १; १०७, ७.
स्थिरस्य १०. ४, ११.
स्थिराणि २०. २८, ३; ३९, ४.
स्थिराय २०. ३१, २.
स्थिरे २०. ४३, २.
स्थिरेण ६. ६५, ३.
स्थिविऽभ्यः २०. १६, ३.
स्थुः ७. ५४, २; १३. १, ५९.
स्थूणाम् ३. १२, ६; १८. ३, ५२.
स्थूणे इति १४. १, ६३.
स्थूरम् २०. १४, १; ६२, १.
स्थूरि २०. १२५, ३.
स्थूलभम् ६. ७२, २.

स्थूलाः ११. १०, २८.
स्थेयुः १६. ४, ७.
स्नपनीः १४. १, ३९.
स्नपयन्ति ५. १९, १४.
स्नपयामसि १०. १, ९.
स्नातः ११. ७, २६.
स्नात्वा ६. ११५, ३.
स्नाव ११. १०, ११; १२.
स्नावऽभ्यः २. ३३, ६; २०. ९६, २२.
स्नावानि १२. ११, ८.
स्नाव्नाऽइव ७. ५२, ९.
स्नाहि १९. ४५, ५.
स्नुषाऽइव ८. ६, २४.
स्नेहितीः २०. १३७, ७.
स्पन्दना ८. ६, १७.
स्पन्द्रम् २०. ८९, ५.
स्परणी ५. ५, ३.
स्परत् ६. ५६, १; १०. ४, ८.
स्पर्धमाना ३. २, ६.
स्पर्धितुम् १९. २२, २१; २३, ३०.
स्पर्शः ४. १६, ४; ५. ६, ३; १८. १, ९.
स्पार्हम् २०. ४३, १; २; ३.
स्पार्हाः २०. १६, ३.
स्पृणुहि ८. ३, ७.
स्पृधः २०. २९, ३; ७०, १९; १०५, १; २.
स्पृश ८. ३, २.
स्पृशत १. ३३, ४; १६. १, १२.
स्पृशन्ताम् १२. २, ३१; ३, ३०; १८. ३, ५७.
स्पृशस्व १३. १, ३४; १४. १, २१; ४०.
स्पृशात् १४. २, ५१.
स्पृशामि ४. ३०, ७.
स्पृष्टः २. २, २.
स्पृहयन्ति २०. १८, ३.
स्फातिः २. २६, ३.
स्फातिम् २. २९, ३; ३. २४, ३; ५; ७; ९. ८, ३; १९. ३१, १; ८; ९.
स्फातिमत्ऽतमा ३. २४, ६.
स्फुरत् २०. ६३, ५.
स्फुरतम् १. २७, ४.
स्फुरति १३. १, ५६.
स्फूर्जति १२. ७, ९.
स्फूर्जयन् ८. ३, ११.
स्फयौ ११. ३, ९.
स्म १. ८, २; ३. १७, ७; ४. ४, ३; १८, ४; ५. २२, १०; ११^{2}; ६. १२३, १; २^{2}; ८. ३, २३; १०. ४, ६; १२. ३, ३; ४६; १८. १, ३३; २०. १४, ४; ३१, ५; ३४, ५; ६२, ४; ६७, १; ७६, ८; ८३, २; १२६, १०.
स्मः १८. ४, ८७.
स्मरः ६. १३०, १.
स्मरतात् ६. १३०, २^{2}.
स्मरम् ६. १३०, १; २; ३; १३१, १; २; १३२, १; २; ३; ४; ५.
स्मरात् ६. १३०, ३.
स्मरेथाम् ८. ४, ७.
स्मसि २०. ७४, १.
स्मसि ७. १०, ३; १९. ४८, ४; २०. १५, ९.
स्य ३. ७, २; ५. २७, १०; ६. १२१, १; ७. १९, १; २०. ७७, २.
स्यः २०. १२, ३; ६७, ६; १२६, २२.
स्यतम् ७. ४३, २.
स्यन्ति ९. २, १४.
स्यन्दते १२. २, २७.
स्यन्दध्वम् १९. ४०, २.

स्यन्दमानाः २. ५, ६; ३. १३, ३; ४.
स्याः ८. १, १६; १८. १, २५.
स्यात् ३. २८, २; १०. ७, २४; ८, २३; ११. ६, २१[2]; १२. ४, १३; ४०; २०. २७, १.
स्याम् २०. २७, २.
स्याम् ६. ५८, १; १९. ४९, ३.
स्याम ५. ८, ९; २०. ६८, ६.
स्याम ३. १०, ५; ७; १६, ३; ४[2]; ५; ५. ३, ५; ६. ३९, २; ४७, १; २; ५५, २; ३; ५८, २; ६२, २; ७९, ३; ९३, ३; ११७, ३; ७. २१, ३; ६; ३५, १; ७०, २; ७७, ११; ८४, ४; ८५, ३; ८८, ३; ९६, १; ९७, १; ९८, १; ११४, ६; ९. १५, २०; १०. ९, २७; ११. १, १२; २१; १२. १, ६२; ३, १७; १३. १, २२; २, ३७; १४. २, ३६; १७. १, ८; ११; १८. १, ५८; ३, १७; ४, ६९; २०. ३७, ७; ७६, २; ८८, ६; १२५, ६; ७.
स्यामि ३. १९, २; ५; ४. १६, ९; ६. ६३, १; १४. १, ५७; १९. ६८, १.
स्युः ४. २१, १.
स्युरिति स्युः २०. ८१, १; ९२, २०.
स्योनम् २. १०, ७; ५. १२, ४; ८; १२. १, ११; १३. २, ७; १४. १, १९; ३०; ४७; ६१; ६३; २, १२; ५१; १८. २, २९; ५३; ४, ८४; १९. ६१, १.
स्योना ३. १२, ५; २८, २; १२. १, ५९; १३. १, १७[2]; १४. १, ६४; २, १७; १८; २६; २७[4]; १८. २, १९.
स्योनाः १. ३३, १; २[2]; ४; ४. २७, ३; १२. १, ३१; १४. २, ९; १८. २, २१; ३, ११; ५१.
स्योनात् १४. २, ४३.
स्योनान् १२. २, २७.
स्योनानि ८. २, २२.
स्योनाम् १२. १, १७.
स्योने इति ४. २६, २; ३; ४; ५; ६.
स्योनौ ६. १४०, ३.
स्रंसयामि ९. ३, २.
स्रक्तयः २. ११, २.
स्रजम् १. १४, १; ८. ६, २६
स्रवताम् ६. ८६, २.
स्रवति ५. १९, ८.
स्रवन्ति ६. २४, १.
स्रवन्तु १. ६, १; १५, १; २. २६, २; ३; १९. १, १.
स्राः ११. २, १९; २६.
स्राक्तयः ८. ५, ४.
स्राक्त्यम् ८. ५, ७.
स्राक्त्येन ८. ५, ८.
स्रामः ११. ४, १४.
स्रावयामसि १. १५, ३; ४.
स्राष्ट्रम् ११. २, १.
स्रिमाः ८. ६, १०.
स्रुक् ९. ६, १७.
स्रुक्ऽकारेण ९. ७, ५.
स्रुचः ५. २७, ५; १९. ४२, २; २०. १०३, ३.
स्रुचः १२. ४, ३४; १८. ४, २.
स्रुचम् ११. १, २४.
स्रुचा ६. ११४, ३; ९. ७, ५.
स्रुतात् १३. २, ४.
स्रुवाऽइव २०. ३१, ४.
स्रुवेण १८. ४, ६.
स्रोतस्यानाम् १९. २, ४.

स्रोत्याः १. ३२, ३; ४. २६, ४; ६. ९८, ३; ८. ७, १५; १०. १, १६.
स्व ६. १२१, १; ७. ८८, ४.
स्वः १. १९, ३; २३, २; ५. ३०, २; ७. ११३, १.
स्वः २. ५, २; ११, ५; ४. ११, ६; १४, २; ३; ४; ५; ६; २३, ६; ५. २६, १२; ६. ३१, १; २; ३३, १; ३५, ३; ४७, ३; ७. १, २; १५, २; ११५, २; ८. ९, १४; ९. ५, १७; १०. ६, १३; ८, १; २१; ११. १, ३७; ७, १४; १९; १२. ३, ३४; १३. १, ७; १६; २, २०; ३९; ४, १; १६. ८, १; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ३०; ९, ३[२]; १८. २, १६; ४५; १९. १३, १; १५, ४; ५२, ३; ५६, ३; ५; २०. ११, ८; १७, ४; ९; ४७, १७; ४८, ४; ५; ५०, १; ६१, ५; ६२, ७; ९; ७२, २; ७५, १; ७७, ४; ९०, ३.
स्वःऽगः ६. १२२, २; ९. ५, १६; १२, ४; १०. २, ३१; ११. १, ७; २०; २८; ३१; ३५; १२. ३, ५; ३८; ४१; ४२; ५४; १३. ६, २; १८. ४, १४; १९. ३, ३.
स्वःऽगम् २. ३४, ५; ४. ३४, ८; ९. ५, २६; ६, ९; ७, ६; १०. ८, १८; ९, ५; ११. १, ३०; १२. ३, १६; १७; २६; ३४; ४४; १३. २, ३८; ३, १४; १८. ३, ४; ४, २; ३; १०; १३; ५६.
स्वःऽगाः १२. ३, ६; १८. ४, ४; ५.
स्वःऽगान् १२. ३, ४२.
स्वःऽगे ४. ३४, २; ५; ६; ७; ६. १२०, ३; ९. ५, १८; १८. ४, ६४; १९. ६१, १.
स्वःऽजित् १३. २, ३०.
स्वःऽजितम् १७. १, १; २; ३; ४; ५.
स्वःऽदृशम् २०. १२१, १.
स्वःऽनरम् २०. ६३, ८.
स्वःऽपतिम् २०. ५४, २;
स्वःऽवती १८. १, २०.
स्वःऽवान् २०. ३६, ३; ५५, २.
स्वःऽवित् ४. २४, ३.
स्वःऽविदः २. १, १; १३. १, ४७; ४८; ४९; ५०; ५१; १९. ४१, १; २०. १७, १.
स्वःऽविदम् १७. १, १५; १८. ४, २९.
स्वःऽविदि १७. १, १३.
स्वःऽविदे ४. २४, ४.
स्वःऽसाः ५. २, ८. २०. ११, ४; १०७, ११.
स्वःऽसाता २०. ७२, ३.
स्वःऽसाम् २०. ३५, ३.
स्वजः ३. २७, ४.
स्वजःऽइव ५. १४, १०.
स्वजन्ते २०. १७, १.
स्वजम् १०. ४, १७.
स्वजस्य १०. ४, १०; १५.
स्वजस्व ६. ८, १; १३३, ५; १२. ३, १२; १४. २, ३९.
स्वजातै १८. १, १५; १६.
स्वजामहे २०. ९५, ३.
स्वजार्य ६. ५६, २; १२. ३, ५८.
स्वजे १९. १, ३.
स्वऽतवः २०. ३६, ६.
स्वदन्तु ५. १२, १०.
स्वदय ५. १२, २.
स्वदयतु ५. २७, ११.

स्वधया॑ ४. ३४, ८; ६. ९६, ३; ९. १५, १६; १२. १, २२; ५, ३; १३. २, ३; १८. १, ४५; ५४; २, ३५^{२}; ३, ४२; ४, ६५.

स्वधा ३. २९, १; ६. ५३, १; ९७, २; १०. १०, १७; ११. ९, १३; १३. ६, २; १८. २, ५२; ४, ७१; ७२; ७३; ७४, ७५; ७६; ७७; ७८; ७९; ८०; ८५.

स्वधाः ४. १. ३; १८. २, २०.

स्वधाऽकारम् १५. १४, १३.

स्वधाऽकारेण॑ १२. ४, ३२; १५. १४, १४.

स्वधाऽप्राणा॑ १०. १०, ६.

स्वधाभि॑ः ७. ५२, ६; ८. ४, ९; ९. १५, ८; १८. १, ४३; ३, ८; ४, ३६; ४७; १९. १०, ३; ४९, २; २०. ८९, ९.

स्वधाम् २. २९, ७; ८. १३, ७; ८; १२. २, ३२; १८. ४, ३९; १९. ३१, ३; २०. ४०, ३; ६३, ३; ६९, १२; १२४, ६.

स्वधाया॑म् १८. ३, ३०; ३१; ३२; ३३; ३४; ३५.

स्वधाऽवः १८. १, २६; २०. २३, ८.

स्वधाऽव॑त् ७. ४२, २.

स्वधाऽव॑तीः १८. ३, ६९; ४, २६; ४३.

स्वधाऽवन् ५. ११, ४; ५; ११.

स्वधाऽव॑न्तः १८. ३, ६८; ४, २५; ४२.

स्वधा॑ऽवन्तौ ५. ९, ८.

स्वधाऽवा॑न् ४. १, ७; १८. २, १०.

स्वऽधि॑तिना ६. १४१, २.

स्वऽधि॑तिम् १८. २, ३५.

स्वऽधिते ९. ४, ६.

स्वऽधि॑त्या १२. ३, ३३.

स्वधे॑ ८. ११, ४; १३, ५.

स्वधे १०. १०, १८.

स्वप॑ःऽतमम् २०. ३५, ६.

स्वऽप॑तिः २०. ९४, १.

स्वपतिम् ८. ६, १६.

स्वप॑न् ६. ११५, २.

स्वपन्त॑ः ६. ४५, २; ९६, ३.

स्वपन्ती॑म् ८. ६, ८.

स्वप॑न्तु ४. ५, ६.

स्वऽपाः ३. ३, १.

स्वपिष्याम॑सि १९. ४७, ९.

स्वप्तु॑ ४. ५, ६^{५}.

स्वप्न॑ ४. ५, ७.

स्वप्न ६. ४६, १; २^{३}; १६. ५, १; ३^{२}; ४^{३}; ५^{३}; ६^{३}; ७^{३}; ८; १०^{२}; १९. ५६, २; ६; ५७, ३; ४^{२}.

स्वप्नऽअभिकर॑णेन ४. ५, ७.

स्वप्न॑ः ११. १०, १९.

स्वप्नऽनंश॑नः २०. १२६, २१.

स्वप्न॑म् १०. २, ९; ३, ६; १९. ५६, १; ४.

स्वप्न॑ऽमुखाः ७. १०५, १.

स्वप्नऽया ५. ७, ८.

स्वप्ना॑य १९. ५६, ३; २०. १८, ३.

स्वप्ने॑ ७. १०६, १; ८. ६, ७.

स्वप्नेऽदुस्वप्न्यम् १६. ६, ९.

स्वप्ने॑न २०. ९६, १६.

स्वप्न्या॑त् ७. १०५, १.

स्वब्दीऽइ॑व २०. ५२, २; ५७, १५.

स्वऽभा॑नवः १८. ४, ६१.

स्वऽभ्यसाः ११. ११, १७.

स्वम् ४. २१, २; ६. ४९, १; ९२, ३; १०७, १; २; ३; ४; १०. १, २५; ८, २४; १२. ४, ३; ६; १५; १४. १, २७; १८. १, २९; ३, ३८; २०. १२, २.

स्वयम् ४. ३०, ३; १२. ४, २७; १४. १, ५७; १५. ११, २; १२, २.

स्वयम्ऽकृताः ८. ५, ९.

स्वयम्ऽभूः ४. ३२, ४; १०. ८, ४४; १९. ५३, १०.

स्वयम्ऽस्रसः ७. ८०, २.

स्वऽयशसः १८. ३, १९.

स्वया ७. ३, १.

स्वयुक्तिऽभिः १३. २, २४; २०. ४७, २१.

स्वयुक्ऽभिः २. ५, ४; २०. ९१, ८.

स्वरः ११. ९, ५.

स्वरन्ति २०. ५२, २; ५७, १५.

स्वरयन्तम् १३. २, २.

स्वरवः ४. २४, ४; १२. १, १३; १८. ३, १२; १९. ४२, १.

स्वऽराजः ९. १, ९.

स्वऽराजम् ८. ९, ९; २०. ९२, १४; ११३, २.

स्वऽराजा ५. २, ८; २०. १०७. ११.

स्वऽराजे १७. १, २२; २३.

स्वऽराज्यम् १०. ७, ३१; २०. १०९, १; २; ३.

स्वऽराट् १८. ३, ५९; २०. ३५, ९.

स्वराति २०. ९२, ६.

स्वः॒रिति स्वः २०. १६, ९; ७२, १.

स्वरीणाम् २०. १६, ७.

स्वरूणाम् १९. १०, ७.

स्वऽरोचिः ४. ८, ३.

स्वर्यमि २. ५, ६; ८. ४, ४; २०. ३५, ६.

स्वऽर्वसुम् ७. ५२, ३.

स्वऽर्वान् ७. ९६, १; ९७, १; २०. १२५, ६; ७.

स्वसरम् ७. ६०, १.

स्वसरे ७. २३, २.

स्वसरेषु २०. ९, १; ४९, ४.

स्वसा ३. ३०, ३; ५. ५, १; ७; ६. १००, ३; १३३, ४; ७. ४८, १; १८. १, १२.

स्वसारः ९. १४, ३.

स्वसारम् १. २८, ४; ३. ३०, ३; १८. १, १४.

स्वसारौ ५. २, ९; २०. १०७, १२.

स्वसुः १८. १, १४; १९. १२, १.

स्वस्तये २. १३, ३; ३५, ३; ४. ३३, ८; ५. १, ८; ६. ९९, ३; ७. ७, १; ९०, १; ८. १, २; १६; १२. २, ११; १७. १, १०; २५; २६; १८. ४, ३०; १९. २४, ६; ३३, ४; ४५, ६; ७; ८; ९; १०.

स्वस्ति १. ३०, २; ३१, ४[२]; ४. १४, ५; ६. ४०, २; ४८, १; २; ३; १२३, १; २; ७. २९, १[२]; ५५, ४; ९१, १; ८. २, ११; १०. ६, ३५; ११. २, ३१; १२. १, ३२; १३. २, ५; ६; १६. ४, ६; १८. २, १२; १९. ८, ३; ७; १५, ४; २०. ४६, २.

स्वस्तिः ७. २९, १.

स्वस्तिऽगाम् २०. ९२, १३.

स्वस्तितम् १९. ८, ३.

स्वस्तिऽदाः १. २१, १; ७. १०, २; ८. ५, २२.

स्वस्तिऽभिः ३. १६, ७; १९. ११, ५; २०. १२, ६; १७, १२; ३७, ११; ८७, ७.

स्वस्तिम् २०. ३६, १०.

स्वस्तिऽमत् २०. ८३, १.

स्वस्तिऽवाहनम् १४. २, ८.

स्वस्त्ययनम् १९. ९, १२.

स्वस्त्या ७. १०२, २.

स्वस्य १२. ४, १०.

स्वस्रा ५. २२, १२.
स्वऽहोता ७. ७७, ५.
स्वा २. २४, १; २; ३; ४; ५; ६; ७; ८; ४. ३२, ५; ७. १०२, ४; २०. ७३, ५.
स्वाः ५. १, ३; १०. ३, ८; १८. १, ५०; २, २९; ३, ७३.
स्वात् १४. २, १९.
स्वाति १९. ७, ३.
स्वादीयः ५. २, ३; ९. ८, ९; २०. ६५, २; १०७, ६.
स्वादु ५. १८, ७; ९. १४, २०; २१.
स्वादुः १८. १, ४८; २०. ४, ३.
स्वादुना ५. २, ३; २०. १०७, ६.
स्वादुऽसंमुदः ७. ६२, ४.
स्वादुऽसंमुदः १३. १, ३.
स्वादोः ५. २, ३; २०. १०७, ६; १०९, १.
स्वाद्मन् २०. ७६, ६.
स्वान् ३. १९, ३; ११. ७, १५; ११, ८; १८. २, २३.
स्वानाम् ९. २, १४.
स्वापय ४. ५, २; ७.
स्वापय ४. ५, ७; २०. ७४, ३.
स्वापयामसि ४. ५, १; ३.
स्वाम् ५. २, ९; ६. ८३, ४; ११०, १; ७. १०२, ५; १०. ५, २३; ११. २, २९; २०. १०७, १२.
स्वार्यं ६. ४३, १.
स्वायाः ३. २८, ५; ६. १२०, ३.
स्वावृक् १८. १, ३२.
स्वासंस्थे इति सुऽआसंस्थे १८. ३, ३९.
स्वाहा २. १६, १; २; ३; ४; ५; १७, १; २; ३; ४; ५; ६; ७; १८, १; २; ३; ४; ५; ३. २६, १; २; ३; ४; ५; ६; ४. ३८, ७; ३९, २; ४; ६; ८; ५. ६, ५; ६; ७; १०; ९, १; २; ३; ४; ५; ६; २१, १२; २४, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; २६, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; २७, १२; ६. १०, १; २; ३; ४८, १; २; ३; ८३, ४; ८४, २; ७. ८७, २; १०२, ५; ६; ८[५]; १०३, १; ८. १, १४; ८, २४[२]; ९. ३, २५; २६; २७; २८; २९; ३०; ३१; १४. २, ५२; १९. ४, १; १७, १; २; ३; ४; ५; ६; ७; ८; ९; १०; २२, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २३, १; २; ३; ४; ५; ६; ७; ८; ९; १०; ११; १२; १३; १४; १५; १६; १७; १८; १९; २०; २१; २२; २३; २४; २५; २६; २७; २८; २९; ४२, २; ४३, १; २; ३; ४; ५; ६; ७; ८; ४५, ६; ७; ८; ९; १०; ५२, ५; २०. ८, ३.
स्वाहाऽकारम् १५. १४, १५.
स्वाहाऽकारेण १५. १४, १६.
स्वाहाऽकृतः ७. ७७, ३.
स्वाहाऽकृतम् ५. १२, ११.
स्वाहेभ्यिः ९. ३, २५; २६; २७; २८; २९; ३०; ३१.
स्वित् ९. १४, ४; ७; १७[२]; १०. २, २; ४, १८; ७, ४; ५; ६; ७; १०; ११; १२; १३; १४; १५; १६; १८; १९; २०; २२; ३९; १३. १, ४१[२]; १८. १, ३३; २०. ९१, १; १२६, २०.
स्विन्नः ६. ११५, ३.
स्वे २. ६, ३; ३. ४, ६; २५, १; ७. १०२, ३; ९. ४, १९; ११. १, २२; २०. २४, ८.

स्वेदाञ्जिऽभिः २०. ९१, ६.

स्वेन २. ६, ४; ६. १४२, १.

स्वेभिः ७. ५४, १; २०. ९१, ११.

ह

ह २. २७, ३; ३. १०, १; ४. २०, ३; ३४, ४[२]; ५. १, ६; ५, ७; ८; ६. २१, १; ३; २४, १; ७. ५, १; ३९, ५; ८१, १; ८. ९, ५; १८[२]; १०. ७, ३१; ८, ३[२]; ५; २८; ४०; ११. ६, १०; ११; १२; १३; १५[२]; ७, ७; १९; १०, ६; ९; १२. ४, २२; ३०; ३१; ३४; ३९; १३. १, ५५; २, २७; ३, २१; २६; १७. १, १९; १८. १, ४; २९; २, १; ४८; ३, २९; १९. ६, १२; १३; ४८, १; ४९, ७; ५३, ५[२]; ६; ८; ९; ५४, ३; २०. १५, २; ३६, ६; ३७, २; ७७, ४; ११८, ४; १२६, २३; १३७, १; १०; ११; १४२, ३; १४३, ७.

हंसः ११. ६, २१.

हंसम् १०. ८, १७.

हंसस्य १०. ८, १८; १३. २, ३८; ३, १४.

हंसाः ८. ७, २४; ११. २, २४; १२. १, ५१.

हंसात् ६. १२, १.

हंसि १. १६, ४; २०. ६३, ७; ११७, २.

हंसि ११. २, २५; २०. २१, ७; ३७, ४.

हंसैःऽइव २०. ९१, ३.

हत ३. १९, ७; ५. ८, ४; १२. २, ४७.

हतः २. ३२, ४[३]; ५. २३, ८[२]; ११[३]; ७. ६१, १; ११५, १; ११. ११, १९.

हतऽभ्राता २. ३२, ४; ५. २३, ११.

हतम् ६. ५०, १; ८. ४, १; ७; १०. ७, ४०; २०. १२६, १८.

हतम् ८. ८, १७; १८; १४. २, ६.

हतऽमाता २. ३२, ४; ५. २३, ११.

हतऽवर्चसः १. १७, १.

हतऽवर्चाः १२. २, ३७.

हतऽस्वसा २. ३२, ४; ५. २३, ११.

हताः २. ३२, ५; ५. २३, २; ४; १२; १०. ४, १२; १३; २०; २०. १३७, १.

हतान् ११. १२, २३; २४.

हताम् ७. ७३, ३.

हतासः २. ३२, ५[२]; ५. २३, १२[२].

हते ३. १३, १; ११. ११, ७; १४.

हत्वा ४. १०, २; १९. ३६, ४; २०. ३४, ३.

हत्वाय ४. ३१, २; २०. ६३, २; १२४, ५.

हत्वी २०. ११, ९.

हनः २०. ५६, ३.

हनः ७. ८१, १.

हनत् ५. १४, ४; १०. १, ५.

हनत् १९. ४९, ९.

हनन् ८. ८, १४; १५.

हनव्याम् ६. ४३, ३.

हनाथ १४. १, ५९.

हनाम ८. ८, १; ११. ११, २३.

हनाव ४. ३२, ६.

हनिष्यति ११. ४, ८; ९; ११; १६.

हनिष्यसि ११. ४, १७.

हनू इति १. २१, ३; ६. ५६, ३; १०. ९, १३; १९. ४७, ८,

हन्त ११. १०, २२.

हन्तन ७. ८२, २.

हन्तवे २०. १९, ५; ६; ४७, १; ७२, ३; १३७, १२.

हन्तवै ४. ३०, ५.

हन्ता १. ७, १; ३. १०, १२; ४. १९, ३; ५. १८, १४; २०. ३४, १०; ६४, ३.

हन्ता॑रम् ७. ७४, १; ८. ३, २२.
हन्ति॑ ५. १८, ४; ५; ७. ५२, १; ८. ३, ११; ४, १२; १३^{२}; १४. २, २४; २०. ५१, २; ८९, ५; ९०, ३; ९६, १३.
हन्ति ५. १९, ४; ८; ९. ४, १७; ५, ७; ११; १०. १, २७^{२}; ४, ५; १४. २, ४१; २०. ९६, ४.
हन्तु॑ ८. ८, ३; ४; १०. १, १९; १३. १, २९.
हन्तु २. ३, ६; ३२, १^{२}; ३. ६, १; ४. ३, ५; ५. २९, १०; ३१, १२; ६. ६७, २; १३४, १; ७. ७३, १; ११९, २^{२}; ८. ३, ४; ४, १६; ७, १४; ८, १६; ११. ११, २०; १२, २७; १२. ३, १४; १३. १, २८; १४. २, १६; १९. ४४, २.
हन्मः १. १८, ३; ८. ६, ४.
हन्मसि ८. २, १२; ६, ५.
हन्मि २. ३१, ३; ५; ३२, ३; ४. ३६, ४; ४०, १; २; ३; ४; ५; ६; ७; ८; ५. १३, ४^{२}; २३, १०; ६. ८, २; ५६, ३; ८. ५, ८; १०. ४, ९; ११. १२, १३; १२. १, ५८.
हन्यता॑म् ५. २३, ७.
हन्यताम् ५. २३, ७; ६. ७०, १; २; ३.
हन्यते॑ १. २०, ४.
हन्यन्ताम् ८. ८, ११.
हन्यन्ते॑ १४. १, १३.
हन्यमा॑ना ५. १८, ११; १२. ७, १४.
हन्वा॑ ६. ५६, ३.
हन्वोः॑ १०. २, ७; ८.
हर २. १९, २; २०, २; २१, २; २२, २; ४. १४, ७; १८, ४; ५. २०, ९; ९. ७, २; १२. ३, ३१; ३६; १४. २, २१.
हरः॑ २. १९, २; २०, २; २१, २; २२, २; २३, २; १८. २, ३६; ३, ७१; १९. २७, ६.
हर॑णाय १. २८, ३; ४. १७, ३.
हरत २. २३, २.
हरति ९. ७, ३; १०, २; ५; ७; ९^{२}; १४. १, ३०.
हर॑न्तः १९. ५५, ६.
हरन्ति ८. १२, ८^{२}.
हरन्तु १४. १, ३९; १९. ४५, ४.
हर॑यः ६. २२, १; ९. १५, २२; १३. १, २४; ३६; ४३; ३, ९; १६; २०. २२, ५; ३१, १; २^{२}; ७७, १; ९२, २.
हर॑ये ५. ११, १; २०. ३२, १.
हर॑सः २. २, २.
हर॑सा २. १२, ४; ५. ५, ४; ६. ९३, २; ८. ३, ४; १०; १३; १५; १०. ५, ४९; १८. २, ५८; १९. ६५, १; ६६, १.
हरा॑त् ४. १८, २.
हरान् ११. ६, १८; १९.
हरा॑मः २. १३, ५.
हरामः ६. ११७, २.
हरामसि ५. १४, ८.
हरामि २. २६, ५; ३. ११, २; ५. ३१, १; २; ३; ४; ५; ६; ७; ८; ९; ८. २, २; १०. ५, ५०; १२. २, ७; ९; ४३; २०. ९६, ७.
हरिऽअश्व ५. ३, ८; ११; २०. २५, ७; ३३, २; ३७, ४; ११७, १; २.
हरि॑ऽअश्वम् २०. १४, ४; ६२, ४.
हरि॑ः १९. ६५, १; २०. ३०, ३^{२}.
हरिऽकेश २०. ३०, ५.
हरि॑ऽकेशः २०. ३१, ३.
हरिऽजात २०. ३०, ५.

हरिणः ३. ७, २.
हरिणस्य ३. ७, १; ५. २१, ७; ६. ६७, ३.
हरिणी इति २०. ३१, ४[२].
हरिणीः १०. ८, ३; १८. ४, ३४.
हरिणीम् १०. २, ३३.
हरितः १०. ३, ३; ८, ३; २०. ३०, ३; ४; १२६, ३.
हरितः १०. ८, ४०; १३. २, ४; ६; ७; ८; ११; २३; २८; ३, १७; २०. १५, ३; ४७, २०; १२३, १; २.
हरितऽभेषजम् ४. ९, ३.
हरितम् ५. २८, ९; ७. १०४, १; ११. २, १२; ३, ८.
हरितस्य १. २५, २; ३.
हरितऽस्रजः १०. ८, ३१.
हरिता ६. २०, ३; २०. ३०, ३; ७३, ५.
हरिताः ४. ३७, ५; १०. ८, ३१.
हरितान् ५. २२, २.
हरिते ५. २८, १.
हरितेन ५. २८, ५.
हरितेभिः ६. ४९, २.
हरितेभ्यः १९. २२, ५.
हरितौ १५. २, ५; १३; १९; २५.
हरिऽपाः २०. ३१, ३.
हरिऽप्रिय २०. २३, ८.
हरिऽभिः ७. १२२, १; २०. ३०, १; २; ३१, २; ३.
हरिऽभ्याम् २. ५, १; ३. १, ४; २०. १२, ३; ७; २३, १; २४, १.
हरिम् २०. ३०, २.
हरिमन्युऽसायकः २०. ३०, ३.
हरिमा १. २२, १; १९. ४४, २.
हरिमाणम् १. २२, ४[२]; ९. १३, ९.

हरिम्ऽभरः २०. ३०, ४.
हरिऽवः २०. ३२, ३; ३३, १; ३६, ३; ३७, ७; ८४, ३.
हरिऽवन् ७. १०२, २.
हरिऽवन्तम् २०. ३०, २; ३१, २.
हरिऽवर्पसम् २०. ३०, १.
हरिऽवान् २०. ३१, ५; ५९, ३.
हरिऽशिप्रः २०. ३०, ४.
हरिऽशिप्रम् २०. ३२, २.
हरिऽश्मशारुः २०. ३१, ३.
हरिऽश्रियम् २०. ६१, १.
हरी इति २०. ३, २; २६, ५; २९, २; ३०, १; २; ३१, १; २; ३; ४; ३७, ६; ३८, २; ४७, ८; ११; ५६, ३; ६९, २; १०; ७३, ४; ८६, १; ९४, २; ९६, १; १००, ३.
हरीणाम् २०. ६४, ५.
हरेः १०. ८, १८; १३. २, ३८; ३, १४.
हर्मि २०. ३५, १.
हर्म्यम् ४. ५, ५; १८. ४, ५५[२].
हर्य १०. ६, ३५; २०. ६, २; ७, ४; १५, ४.
हर्यत १. ८, २; ३. ३०, १; ५. ७, ६.
हर्यतः १८. १, २३; २०. १५, २; ३०, ४; ३१, ५.
हर्यतम् २०. ३०, १; ५; ३२, १.
हर्यतम् १. ७, ३.
हर्यतस्य २०. ३१, ४; ५.
हर्यता २०. ३१, १.
हर्यते २०. ३१, १;
हर्यन् २०. ३२, २.
हर्यन्तम् २०. ३२, २.
हर्यन्तु ३. ८, २.
हर्यमाणः २०. ३२, १.

हर्यसि २०. ३०, ५; ३२, १.
हर्यासि १२. ३, २३.
हर्योः २०. ३८, ५; ४७, ५; ७०, ८.
हर्षध्वम् ६. ९७, ३; १९. १३, ६.
हर्षन्ताम् ३. १९, ६.
हर्षमाणाः ४. ३१, १.
हर्षय ५. २०, ८.
हलीक्ष्णात् २. ३३, ३; २०. ९६, १९.
हवन्त २०. १०१, २.
हवन्ते ४. २४, ५; २०. ३४, ९; ८५, ३.
हवन्ते १८. १, ४१[२]; ४२; ४, ४५[२]; ४६.
हवम् १. १५, २; २. ५, ४; ३०, ३; ३. ३, ६; ४. २४, १; ५. ८, १; २; ३[२]; ६. २, १; ९. २, ७; २०. २६, २; ५०, २; ५२, ३; ५७, १३.
हवामहे ७. ७७, १; २०. ३९, १; ७०, १६; ९६, ५; ९८, १.
हवामहे ३. १५, १[२]; २; २०, ४; ६; २१, ८; २४, २; ४. २३, ४; ५. ३, ११; ७, ४; ७. ६, २; ४१, १; ६५, १; १३. २, ४३; १६. १, १३; १९. १५, २; २४, ७; ५८, २; २०. १, १; ३, ३; ६, १; १४, १; २४, ४; ९; २६, १; ३८, ३; ४७, ९; ५६, १; ६२, १; ७०, ११; ११०, २; ११८, ३; १२१, २.
हविः १. ४, ३; ७, ३; ८, १; ३. १०, ५; १३; ५. १२, ११; २७, १२; ६. ५, ३; २७, २; ३९, १; ५०, २; ९७, १; ७. ४८, २; ५७, १; ७०, २; ७३, ४; ५; ७५, २; ८१, १; ८२, १; १०३, १; ११४, ५; ८. ७, २०; ९. ५, ३८; ६, २; ११. १, ४; ९, १८; १२. २, ३७; ४, ४०; ४८; १८. १, ५२; २, १; ३; ३, ६४; ४, २; ३५; ६३; १९. ६, १०; २७, ११; १२; १३; ४२, १; ५२, ५; २०. १२६, १२; १३.
हविःऽअर्दः १८. ३, ४८.
हविःऽअदान् ४. ३७, ८; ९.
हविःऽकृतः ७. २९, १; १९. ४२, २.
हविःऽकृतम् ९. ६, १३.
हविःऽदाः ५. १, ७.
हविःऽदाम् ७. ८३, २.
हविःऽधानम् ७. ११४, ३; ९. ३, ७; १४. २, ३४.
हविःऽपाः १८. ३, ४८.
हविःऽभिः १८. ३, ६३; ४, ५४; २०. ८८, ६.
हविःऽमथीनाम् ८. ४, २१.
हविर्नः ३. ४, ३.
हविर्षः ७. ४९, २; १८. १, ६०; १९. ५२, ५; २०. ७२, ३.
हविषा १. १२, २[२]; १५, १; ३१, १; ३; २. २६, ३; ३. ११, १; ३; ४; १५, ५; १७, ५; १९, २; ४. २, १; २; ३; ४; ५; ६; ७; ८; ६. ४०, १; ४१, १; २; ६४, २; ६५, २; ७३, २; ७५, १; ७८, १; ८०, १; ३; ८७, ३; १२५, २; ७. ५, ३; ४; ७३, १; ८४, ३; ९९, १; १०३, १; ११४, ६; ९. २, १; १२. १, ६०; २, ३२; १८. १, ४९; २, २९; ३, १३; १९. १, १; २; ३; ६, १०; ५८, १; २०. ९६, ६; ८; ९.
हविषाम् ६. १५, ३.
हविषे १८. १, ५६; ५७; २, ३४.
हविष्मतः २०. १५, २.
हविष्मती ६. ८४, २; २०. १०३, २.
हविष्मते ४. ३०, ६; २०. १७, ८.

हविष्मन्तः २०. २३, ७; १०२, २.
हविष्मन्तम् ६. ३९, १; २०. १४०, १.
हविष्मान् २०. ८९, ४; ९०, १.
हवींषि ४. २६, ४; ५. १२, १०; ७. ४८, ३; ९. ७, ३; १८. ३, ४२; ४४; ४६; ४, ६९.
हवीमऽभिः २०. ७२, ३[२]; १०१, २.
हवे ५. ३, ८.
हवेते इति २०. ३४, ८.
हवेभिः २०. ३७, ९.
हवेषु १८. १, ४४; ४७; १९. ११, १; १३, ११.
हवेऽहवे ७. ९१, १.
हव्यः ६. ९८, ३; २०. ३६, १; ६७, ७; ७३, १; १०४, ३.
हव्यऽदातिम् ६. १२५, ३; ७. ११४, २.
हव्यम् ३. ३, ४; १५, ३; ४; ४. २३, २; ३९, १०; ५. ८, ३; १२, १०; २७, ११; ७. २१, २; ४८, १; ७०, १; २; ८. ९, २१; ११. १, २५; १२. १, २२; २, ८; ५३; १८. १, ३०; १९. ४, १[२]; ४२, ३; ५८, ६.
हव्यऽवाहः १८. ४, १.
हव्यऽवाहनः ७. २१, १.
हव्यऽवाहम् ४. २३, ४; १२. १, २०; १४. ४, ४१; २०. १०१, २.
हव्यऽसूदः २०. ८८, ५.
हव्या ७. ४९, २.
हव्या ३. १०, ६; ६. १२५, ३; ७. ११४, २; १८. १, ५१; ४, १.
हव्यानि १८. ३, ४२; २०. १४१, ४.
हसः १५. २, १९.
हसः ११. १०, २४.
हसामुदाः ७. ६२, ६.
हसामुदौ १४. २, ४३.
हसाय १२. २, २२.
हस्तऽअवनेजनम् ११. ३, १३.
हस्तः ४. १३, ६; १९. ७, ३.
हस्तऽकृताम् १०. १, १.
हस्तऽगृह्य ५. २०, ९; १४, ४; १७, २; १४. १, २०.
हस्तऽग्राभस्य १८. ३, २.
हस्तम् ५. १७, ८; ७. १०, ४; १२. ३, १७; १४. १, ४८[२]; ४९; ५०; ५१[२]; २, ३९; १८. ४, ५६.
हस्तयोः १. १८, २; १८. ३, १२.
हस्तात् १८. २, ५९; ६०.
हस्ताभ्याम् ३. ११, ८; ४. १३, ७[२]; ६. १०२, ३; ११८, १; १०. ७, ३९; ११. ४, १७[२]; १९. ५१, २.
हस्ताम् ११. १, २४.
हस्ताय २०. ९२, १७; १०५, ५.
हस्तिनः ३. २२, ४.
हस्तिनम् ४. ३६, ९.
हस्तिनि ६. ३८, २.
हस्तिनीऽइव ९. ३, १७.
हस्तिन्याः ६. ७०, २.
हस्तिऽवर्चसम् ३. २२, १; ५.
हस्तिषु १२. १, २५.
हस्ती ३. २२, ३; ६; ६. ७०, २.
हस्तीऽइव १०. १, ३२.
हस्ते ४. २०, ४; ७. ५२, ८; ८. ६, १४; ११. १, १०; २०. ३६, ९.
हस्तेन ५. १७, ३; ९. ७, ५; १०. ६, ३.
हस्तेषु ४. १४, २; ६. १२२, ५; १०. ९, २७; ११. १, २७.

हस्तौ ६. ८१, १; ७. २७, ८; ११४, ३; ८. १, ८; ११. १०, १४; १५; १९. ४९, १०.
हाः ७. ८०, ३.
हापयामसि १. ११, ३.
हायनः ६. १४, ३; १९. ३९, १०.
हायनान् ३. १०, ९; ८. २, २१; ११. ८, १७.
हायनीः १२. १, ३६.
हायि १८. ३, ९.
हारिद्रवेषु १. २२, ४.
हारिऽयोजन २०. ३५, १६.
हार्दिम् ६. ८९, १; २; १८. ४, ५८.
हासन्ते ४. ३६, ५.
हासिषुः ६. ४१, ३; ८. २, २६.
हासिष्ट ९. ४, २४.
हासिष्टम् १६. ४, ५.
हासिष्टाम् १६. २, ५; ३, २[२]; ३[२]; ४[२].
हासीत् २. २८, ३; ७. ५५, ४; ८. १, १५; १३. १, १२; १६. ४, ३.
हास्त १८. २, २४.
हास्तिनम् ६. ७२, ३.
हास्थाः १८. ३, ७३.
हास्महि ५. ३, ७.
हास्यन्ति ११. ३, २८; २९; ४, ७.
हि १. ५, १; ७, १; १०, १; २; ३५, २; २. ६, ५; ९, ३; २५, १; ३६, ३; ३. १, २; ४, ६; ९, ५; १३, ३; २२, ६; ४. १, ४; ३, १; १३, ३; १४, १; १९, ७; २५, ४; २६, १; २; ३२, ४; ३३, ६; ५. ४, २; ५, २; ११, ५; ७; ११; १३, १; १८, ६; २२, २[२]; ६. २७, २; ५१, २; १०६, ३; ११०, १; ११२, ३; १२५, १; ७. ३, १; ८, १; १५, ३; २१, ५; ६; ५८, ५; ६७, १; ७७, १; ११; ११४, ६; ११५, १; ८. १, ६; ८, ६; ९, ७; २४; ९. १, १; ३; १०; २, ९; ३, २२; ५, १३; १४, ८; १५, ७; २०; १०. १, २८; २, ७; ४, १९; ९, ४; १०, १३; १४; १५; २२; २३[२]; २७; ३३; ११. २, २८; १०, ३२; १२. २, ५५; ४, ४; ७, ५[२]; १०, ७; १८. १, ३३; ३८; ६०; ३, १९; ५१; ४, ५९; ६१; १९. ५८, ४; २०. १, २; ३, १; १२, ४; ५; १३, ३; ४; १४, २; ४; १६, ७; १२; २०, ५; २१, १; २३, ६; २४, ६; २९, १; ३०, २; ३१, ५; ३८, १; ४०, १; ४७, ७; ५४, २; ५६, २; ४; ५; ६; ५७, ८; ६०, १; ४; ५; ६; ६२, २; ४; ६३, ६; ६४, २; ३; ४; ६६, ३; ६७, १[२]; ७०, ३; ७१, ४; ५; ६; ७२, १; ३; ७४, १; ७६, ७; ७८, ३; ८५, ३; ९१, ४; ११; ९४, ५; ९८, १; १००, १; १०३, ३; १०८, २; ११३, २[२]; ११५, १; ११८, १; २; १२६, १; २; १४; १४०, १.
हिंसन्ति ५. १९, ८.
हिंसितव्यः ५. १८, ६.
हिंसितस्य ५. २८. ६.
हिंसित्वा ५. १८, १२; १९, १; ११.
हिंसिषुः २. २८, १; ७. १०७, १; १४. २, ९.
हिंसिष्ट १८. १. ५२.
हिंसिष्टम् ५. ९, ८; ६. १४०, २; ३; ११. २, १; १४. १, ६३; १९. ४०, ३.
हिंसीः ९. ३, १६; १०. ९, ११; ११. २, २०; २९; १२. १, ३४; १८. ४, ३०.
हिंसीत् ३. २८, ५; ६; ६. २७, ३; ७. ५७, १.

हिंस्तै १२. ४, १३.
हिंस्रः ८. ३, ३.
हिंस्रम् ८. ३, ९.
हिंस्रा ८. ३, ४.
हिङ् ९. १०, १; ४; ६; ८; १५, ६.
हिङ्ऽकरिक्रती ९. १, ८.
हिङ्ऽकारः ११. ९, ५.
हिङ्ऽकृण्वती ७. ७७, ८; ९. १५, ५; १२. ७, १०.
हिणुत ६. १३०, १; २; ३; १३१, १; २; १८. ४, ४०.
हिणोमि १०. ५, २३; १२. २, ४; ८; १०.
हिण्मः ७. १२०, ३; १०. १, १५; १९. ५७, ३.
हिण्मसि ५. ३१, १०; १०. १, ३०.
हितः ५. ४, ७; १३. ३, २३; २०. ४७, २; ६७, ६; १३७, १३.
हितऽप्रयसः २०. ९२, १५.
हितम् ३. १३, ३; ८. ६, २०; १०. २, २४; २५; ८, ३४; ११. १०, ३४; १८. २, ७.
हिता १०. २, २४; २५; ११. १, २३; ९, २२; २०. १४१, ४.
हिताः ११. २, २४; ९, ११; १५; १२. १, ४९; १३. ४, १०.
हिते २०. ९, ३; ४९, ६.
हित्वा ४. ११, ६; ५. २०, ३; ६. २८, १; १७. १, ८; १८. २, ४७; ३, ५८.
हिन ६. १६, २.
हिनस्ति २. १२, २; ३; ५. १८, १३.
हिनस्ति ५. १७, ७; १५. ५, ३; १६.
हिनुतात् १८. २, ४.
हिनोति ४. १, ६; ८. ४, १३.
हिनोमि ५. २२, ४; २०. ३५, ४.
हिन्वन् २०. ३१, २.
हिन्वन्तः २०. ३०, २.
हिन्वन्ति ५. २, ९; ६. १०१, २; २०. १०७, १२.
हिन्वन्ति ४. ८, ७; २०. १०९, २.
हिन्वन्तु १. ४, २.
हिन्विरे २०. १०६, २.
हिमः ७. १९, २; १३. १, ४८.
हिमम् १३. १, ४६; ४७.
हिमऽवतः ४. ९, ९; ५. ४, २; ८; ६. २४, १; १९. ३९, १; ८.
हिमऽवताम् ६. ९५, ३.
हिमऽवन्तः ४. २, ५; १२. १, ११.
हिमस्य ६. १०६, ३; १९. ४९, ५.
हिमाऽइव २०. १६, १०.
हिमाः २. २८, ४; १२. २, २८.
हिरण्यऽकशिपुः ५. ७, १०.
हिरण्यऽकेश्यै ५. ७, ९.
हिरण्यऽगर्भः ४. २, ७; १०. ५, १९.
हिरण्यऽगर्भम् १०. ७, २८.
हिरण्यऽजाः ४. १०, १; ४.
हिरण्यऽजित् ७. ५२, ८.
हिरण्यऽज्योतिषम् १०. ९, ६.
हिरण्यऽतेजसा १९. २६, ३.
हिरण्यऽत्वचसः १३. २, ८.
हिरण्यऽद्रापये ५. ७, १०.
हिरण्यऽनेमयः १८. ४, ८९.
हिरण्यऽपक्षम् १८. ३, ६६.
हिरण्यऽपाणिः ७. १५, २.
हिरण्यऽपाणिम् ३. २१, ८.
हिरण्यऽपावाः १८. ३, १८.
हिरण्यऽबन्धना ५. ४, ४; ६. ९५, २; १९. ३९, ७.

हिर॑ण्यम् १. ९, २; ३५, १; २; ३; ३. ३६, ७; ५. १, ३; २८, ६[२]; ११; ६. ७१, १; १२४, ३; ९. ५, १४; २९; १०. ७, २८; ११. १, २८; १२. १, ४४; ३, ५०; १४. १, ४०; १८. ४, ५६; १९. २६, १; २; २७, ९; १०; २०. ७३, ४.

हि॒र॒ण्ययः॑ ४. २, ८; ६. ८२, ३; ७. ८८, १; ९. १, २१; १०. २, ३१; ३, ३; १९. ३०, ५; २०. १५, २; ३८, ५; ४७, ५; ७०, ८; ११८, २.

हि॒र॒ण्यय॑म् ७. १०४, १; १०. ७, ४१; ११. २, १२; २०. ११, ९; ९२, १३.

हि॒र॒ण्यया॑ ५. ४, ५.

हि॒र॒ण्यया॑ः ५. ४, ५.

हि॒र॒ण्ययी॑ ५. ४, ४; ६. ९५, २; १९. ३९, ७.

हि॒र॒ण्ययीः॑ ४. ३७, ९; ५. ४, ५; १०. ६, १०.

हि॒र॒ण्ययी॑भिः १०. ४, १४.

हि॒र॒ण्ययी॑म् १०. २, ३३.

हि॒र॒ण्यये॑ १०. २, ३२; १०, १२; १७.

हि॒र॒ण्यये॑न २०. १४३, ४; ५.

हिर॑ण्यऽवक्षसे १२. १, २६.

हिर॑ण्यऽवक्षाः १२. १, ६.

हिर॑ण्यऽवर्णः १९. २४, ८.

हिर॑ण्यऽवर्णम् १४. १, ६१.

हिर॑ण्यऽवर्णा ५. ७, १०; ९. १, ४.

हिर॑ण्यऽवर्णाः १. ३३, १; ३. १३, ६.

हिर॑ण्यऽवर्णे ५. ५, ६; ७.

हिर॑ण्यऽशृङ्गः १९. ३६, ५.

हिर॑ण्यस्यऽइव १२. १, १८.

हिर॑ण्यऽस्रक् १०. ६, ४.

हिर॑ण्यऽहस्तः ७. १२०, १.

हिर॑ण्यानाम् ४. १०, ६.

हिर॑ण्ये ६. ३८, २; ६९, १.

हिर॑ण्येन १०. १०, १६.

हि॒राः १. १७, १; ७. ३६, २.

हि॒राणा॑म् १. १७, ३.

हिरु॑क् ४. ३, १[३]; ९. १५, १०.

ही॒डि॒ताः १२. ४, २८; ४९.

ही॒य॒ताम् ८. ४, १०.

ही॒य॒ते १०. ८, १५.

हु॒तः १८. ४, १५.

हु॒तऽभा॑गाः १. ३०, ४; १८. ३, २५; २६; २७; २८; २९; ३०; ३१; ३२; ३३; ३४; ३५; ४, १६; १७; १८; १९; २०; २१; २२; २३; २४.

हु॒तम् ३. २१, १; २; ३; ४; ५; ६; ७; ६. ७१, २; ९. ४, ३; १५. १२, ६; १३, १४.

हु॒ताना॑म् १८. ४, १५.

हु॒ताम् १२. ४, ५३.

हु॒ते ५. २१, २; ११. ११, ६; १५. १४, ७.

हु॒तेभ्यः॑ ७. १०२, ७.

हु॒वा॒नः २०. २३, १.

हु॒वे ३. ८, २; ३; ७. ९१, १; ११४, ७; २०. २६, ३[२].

हु॒वे ४. २६, ३; २८, ३; ३८, १; २; ४; ५. २५, २; ६. ७७, २; ९९, १; १०८, २; ७. ५०, १; ११५, २; ८. २, ६; ७, ६; २३; २४; ११. १२, ९; १८. १, ५९; १९. ४२, ४; २०. ६७, ७.

हु॒वे॒म ७. ४१, २; ९०, १; २०. ११, ११; ९६, ५; १४३, १.

हु॒वेय॑ २०. १४१, ३.

हू॒तः ४. ३१, २.

हू॒म॒हे २०. ८०, २.

हू॒यमा॑नः २०. ८, २.

हू॒यमा॑ना १०. १०, ९.
हू॒यमा॑नाः १८. ३, १९.
हू॒यसे॑ २०. ६, ९; १२०, १.
हू॒य॒से॒ २०. ५, ६; ११४, २.
हृ॒णी॒षे॒ ८. ४, १४.
हृ॒तम् ५. २९, ५; १२.
हृ॒ता १२. ८, २.
हृ॒त्तः १८. १, २३.
हृ॒त्ऽद्यो॒तः १. २२, १.
हृ॒त्ऽद्योत॑नः ५. २०, १२.
हृ॒त्ऽब॒लैः ५. १८, ८.
हृ॒त्ऽभिः ९. १, १.
हृ॒त्ऽसु ३. २, ५; ८. ८, २; १२. २, ३३; १४. २, ५.
हृ॒त्सु॒ऽअस॑ः १८. १, ६.
हृ॒दः ३. २५, ६; ६. ४२, १; ७४, २; ७. १००, १; ९. १, ६; १३, ८; १२. ३, ३२; १८. १, १४; १९. २८, १; २; ३; ३०, ४.
हृ॒द॒य॒ऽआ॒म॒यः ५. ३०, ९.
हृ॒द॒य॒ऽआ॒म॒यम् ६. १४, १; १२७, ३.
हृद॑यम् २. २९, ६; ३. १३, ७; ५. २०, ३; २९, ४; ६. १३९, १; २; ३; ९. ६, २; १२, ११; १३, १४; १०. २, २६; ४, २५; ९, १५; ११. ७, २४; १२. १, ८; ३५; १६. ३, ६; १८. १, १५; १९. २८, ४; ५२, ४.
हृ॒द॒य॒ऽश्रि॒षम् ६. ९, २.
हृद॑यस्य ९. १३, २२.
हृद॑यात् २. ३३, ३; ६. ७६, १; ७. ११९, १; ९. १३, ८; १२; १९. ५२, ४; २०. ९६, १९.
हृद॑यानि ३. ८, ६; ६. ६४, ३; ९४, २; ११. ११, २१.
हृद॑याय ६. ९०, १.
हृ॒द॒या॒वि॒धम् ८. ६, १८.
हृद॑ये ५. १८, ५; ८. ३, ६; १२; ६, २४; १०. ५, ४८.
हृद॑येन ३. २०, ९; ५. २१, २.
हृद॑येषु ४. ३१, ७; ६. ७३, २.
हृ॒द॒य्य॒मि ६. १८, १.
हृ॒दा २. १२, ३; ४. २१, ५; ३९, १०; १८. ३, ६६; २०. ३५, २; ८७, २.
हृ॒दि ३. २, २; ४; ७, २; २५, १; २; ३; ६. ९, ३; १८, ३; ७. ३७, १; ११. ११, १; १३; १९. ९, ५; २०. २४, ८.
हृ॒दे ६. १२, ३; ८. २, १४; ७, १७; २०. ४, ३; १२६, १५.
हृ॒द्द्यो॒त॒ऽभे॒ष॒जम् ६. २४, १.
हृद्यः १६. ३, ५.
हृ॒षि॒तास॑ः ४. ३१, १.
हृ॒ष्य॒ति॒ २०. १२६, ७.
हेड॑ः १९. ३, ४.
हेड॑म् १२. ४, २०; २१; ३२.
हेड॑सि ७. २१, ३.
हे॒तय॑ः ३. २६, १; ४. ३७, ८; ९; ५. २२, १०; २०. ५१, ४.
हे॒तये॑ १. १३, ३.
हे॒तार॑म् २०. १०५, ३.
हे॒तिः १. २६, १; २. ११, १; २४, १; २; ३; ४; ५; ६; ७; ८; ४. २१, ७; ६. २७, २; ३; २९, १; ७. ७९, १; ८. २, ९; १०. ५, ४३; ११. २, २२; १२. ७, ८.
हे॒तिम् ५. ७, ७; ६. ५९, ३; १२. ४, ५२.
हे॒ति॒ऽमन्त॑ः ५. १८, ९.
हे॒ते॒ ५. ५, ९[४].
हे॒तोः ९. १३, ३.

हेत्याः २. ११, १; ४. १०, ५; ५. २९, ११; ८. ३, १८.
हेमन्तः ६, ५५, २; १२. १, ३६.
हेमन्तऽजब्धः १२. १, ४६.
हेमन्तान् ३. ११, ४; २०. ९६, ९.
हेमन्ताय ८. २, २२.
है ६. ५०. २[३]; १८. ४, ६६.
हैमनौ १५. ४, १४; १५.
हैमऽवतीः १९. २, १.
हैरण्यैः १३. २, ११.
होतः ३. १५, ७; ७. १०२, १.
होतः ५. १२, ९; २०. ६७, ५.
होता १. ११, १; २. २८, २; ४. ३२, २; ५. १२, ३; १७, २; ६. ७१, १; २; ११०, १; १०. ९, २६; १०, १९; १८. १, २९; ३०; ४, १५; १९. ४२, १; ५९, ३; २०. २३, २; ७६, १; १०१, ३.
होतारः ५. ३, ५; २७, ९.
होतारम् ३. २१, ५; १८. १, २०; २१; २०. ६७, ३; १०१, १; १०३, २.
होतारा ५. १२, ७.
होतुः ५. १२, ११; ९. १४, १.
होतृऽसदनम् ७. १०४, १.
होत्राः ११. ८, १४; ९, १९; १८. ४, २८.
होत्राभिः १८. १, २२.
होत्राम् ८. ४, ६.
होत्राऽविदः १८. ३, ४७.
होत्रियम् २०. २५, २.
होत्रेण ९. २, ६.
होम २०. ७१, १५.
होमः ८. ८, १७.
होमम् ४. ३८, ५.
होमाः ८. ९, १८; १९. १, २.
होमैः ६. ९३, २; १०. ६, ३५.
होष्यामि १५. १२, २.
ह्यः ९. १५, ९; २०. ९७, १.
ह्रदः ६. १०६, १.
ह्रदम् ६. ३७, २; २०. १७, ७.
ह्रदस्य ४. १५, १४; ६. १०६, २.
ह्रियमाणा १२. ८, २.
ह्रूडुः १. २५, २; ३.
ह्लादिकाऽवति १८. ३, ६०.
ह्लादिके १८. ३, ६०.
ह्वयताम् १. १, ४; १९. ५८, २.
ह्वयति ९. ११, १.
ह्वयतु ३. ३, ३[३].
ह्वयन्ति ९. ६, १३.
ह्वयन्ति ९. ६, १३; २०. ९६, २.
ह्वयन्तु ३. ३, ५.
ह्वयन्तु ३. ४, १; ४; ७.
ह्वयन्ते २०. ८९, ४.
ह्वयस्व ५. २०, ८; १२. ३, १.
ह्वयामसि ५. ३०, १७; ६. ९०, २; ७. ५८, ३; ८. १, १५.
ह्वयामहे ५. १०, ८; ७. ६२, ३.
ह्वयामहे ८. ११, २.
ह्वयामि ६. ९९. १; ८. ७, ४; १८. २, २१.
ह्वये १. ४, ३; ५. १०, ८; ६. २३, १; ७. ७७, ७; ९. ५, ३०; १५, ४.
ह्वयेथाम् १२. ३, ३; ४०.
ह्वारम् ४. १, २.
ह्वे १७. १, १; २; ३; ४; ५.

Bayerische Staatsbibliothek München